नं. ५०४५

ऋग्वेद संहिता पद-पाठ-
सस्वरा

× × × ×

पत्र ८१० — पृ. १८८६

संहिताब्राह्मणानि

© Dharmartha Trust J&K. Digitized by eGangotri

शाकलशाखीयर्ग्वेदसंहिता पदपाठः सस्वरः

५०४५

5045

1 to 126

1 to 120

1 to 119

1 to 107

1 to 115

1 to 118

1 to 105

810

© Dharmartha Trust J&K. Digitized by eGangotri

॥ इतिग्रथमाहकप्रारंभः॥ प्रत्रे

१ १८११ १२६

५०४२

© Dharmartha Trust J&K. Digitized by eGangotri

प॰भा॰ श्रीगणेशायनमः॥ॐ॥अथऋग्वेदाम्नायेशाकलकेसूक्तप्रतीकऋक्संख्यऋषिदैवत
१ छंदांस्यनुक्रमिष्यामोयथोपदेशंनह्येतज्ज्ञानमृतेश्रौतस्मार्तकर्मप्रसिद्धिर्मंत्राणांब्राह्म
णार्षेयछंदोदैवतविद्याजनाध्यापनाभ्यांश्रेयोधिगच्छत्येताभ्यामेवानेवंविद्योयातमो
योनिछंदांसिभवंतिस्थाणुंवर्छतिगर्तेवापात्यतेप्रमीयतेवापापीयान्भवतीतिविज्ञा
यते॥१॥अथऋषयःशतर्चिनआद्येमंडलेक्षुद्रसूक्तामहासूक्तामध्यमेषुमाध्य
माःक्वचित्कथंचिदविशेषितंब्रह्मसत्रऋषिमन्त्रियमनुक्तगोत्रमांगिरसंविद्याद्यस्यवाक्यं
सऋषिर्यातेनोच्यतेसादेवतायदक्षरपरिमाणंतच्छंदोर्थेप्सवऋषयोदेवताश्छंदोभिर ३

© Dharmartha Trust J&K. Digitized by eGangotri

म्यथावास्तिस्र एव देवताः क्षित्यंतरिक्षद्युस्थाना आग्निर्वायुः सूर्य इत्येवंव्याहृतयः प्रोक्ता व्यस्ताः
समस्तानां प्रजापतिरार्षंतु प्रजापतिरोंकारः सर्वदेवत्यः पारमेष्ठ्यो वा ब्राह्मो दैव आध्या
त्मिकस्तत्तत्स्थाना अन्यास्तद्विभूतयः कर्मपृथक्त्वाद्धि पृथगभिधानस्तुतयो भवंत्येके
ववा महानात्मा देवता स सूर्य इत्याचक्षते स हि सर्वभूतात्मा तदुक्तमृषिणा सूर्य आत्मा
जगतस्तस्थुषश्चेति तद्विभूतयोऽन्या देवतास्तदप्येतदृचोक्तमिंद्रं मित्रं वरुणमग्निमाहु
रिति यथाभिधानं त्वनुक्रमिष्यामः प्रायेणैंद्रे मरुतौ राज्ञां यदानस्तुतयः ॥२॥ अथछं
दांसि गायत्र्युष्णिगनुष्टुप्बृहती पंक्तिस्त्रिष्टुप्जगत्यतिजगती शाक्वर्यतिशाक्वर्यष्ट्यत्य

© Dharmartha Trust J&K. Digitized by eGangotri

प.भा. षीधस्यनिधनयश्चतुर्विंशास्यसप्ताक्षराणिचतुरुत्तराण्यूनाधिकेनैकेननिचृद्भुरिजौद्वाभ्यां
२ विराट्स्वराजौपादपूरणार्थंतुक्षैप्रसंयोगैकाक्षरीभावान्व्यूहेद्दायेतुसम्पन्नवेगैःपादवि
2 शेषात्संज्ञाविशेषास्तानानुक्रामंतएवोदाहरिष्यामोविराड्रूपाविराट्स्थानाश्चबहूना २
अपित्रिष्टुभएवेत्युद्देशस्तत्रदशैकादशद्वादशाक्षराणांवैराजत्रैष्टुभजागताइतिसं
ज्ञाअनादेशेष्टाक्षराःपादाश्चतुष्पदाश्चर्चः॥३॥प्रथमंछंदस्त्रिपदागायत्रीपंचकाश्च
त्वारःषट्कश्चैकश्चचतुर्थश्चतुष्कोवापदपंक्तिःषट्सप्तैकादशाउष्णिग्गर्भात्रयःसप्तकाः
पादनिचृन्मध्यमःषट्कश्चोदात्तनिचृद्दशाकश्चैवमध्यायस्यास्तुषट्सप्तकाष्टकांता २

© Dharmartha Trust J&K. Digitized by eGangotri

वर्द्धमाना विपरीता प्रतिष्ठा द्वौ षट्कौ सप्तकश्च ह्रसीयसी॥५॥ द्वितीयमुष्णिक् त्रिपदा तस्या
द्वादशाद्यश्चेत्पुरउष्णिक् ककुम्मध्यमश्चेत्कपैंकुत्रैष्टुभजागतचतुष्काः ककुम्न्यंकुशिरैकादशि
नौः परः षट्कस्तनुशिरा मध्येचेत्पिपीलिकमध्या पंचकस्त्र्यष्टका अनुष्टुप्गर्भा
चतुःसप्तकोष्णिगेव॥६॥ तृतीयमनुष्टुप् पंचपंचकाः षट्श्चेको महापदपंक्तिर्जागतावृह
कश्च कृतिर्मध्येचेद्दष्टकः पिपीलिकमध्या नवकयोर्मध्ये जागतः काविराण्नवैराजेत्र
योदशौर्नष्टरूपी दशकास्त्र्यो विराकेकादशाकावा॥७॥ चतुर्थं बृहती तृतीयो द्वादशा
द्यश्चेत्पुरस्ताद्बृहती द्वितीयश्चेन्न्यंकुसारिण्युरोबृहती वास्कंधोग्रीवी वांत्यश्चेदुपरि

© Dharmartha Trust J&K. Digitized by eGangotri

२

प॰भा॰ ष्टौबृहत्यष्टिनोमध्येदशकौविष्टारबृहतीत्रिजागतोर्ध्वबृहतीत्रयोदशिनोमध्येष्ट

३ कःपिपीलिकमध्यानवकास्त्र्येकादश्यष्टिनोविषमपदाचतुर्नवकाबृहत्येवा॥७॥पं

3 चमंपंक्तिःपंचपदाथचतुष्पदाविराड्दशाकैर्युजौजागतौसतोबृहतीयुजौचेद्विपरी

तौपूर्वौचेत्प्रस्तारपंक्तिरन्त्यौचेदास्तारपंक्तिराद्यान्त्यौचेत्संस्तारपंक्तिर्मध्यमौचेद्विष्टा

रपंक्तिः॥८॥षष्ठंत्रिष्टुप्त्रैष्टुभपदाद्वौतुजागतौयस्याःसाजागतेजगतीत्रैष्टुभेत्रिष्टु

प्वैराजौजागतौचाभिसारिणीनवकौवैराजस्त्रैष्टुभश्चद्वौवावैराजौनवकस्त्रैष्टुभश्च

विराट्स्थानैकादशिनस्त्रयोष्टकश्चविराड्रूपाद्वादशिनस्त्रयोष्टकश्चज्योतिष्मती ३

© Dharmartha Trust J&K. Digitized by eGangotri

यतोऽष्टकस्ततोज्योतिश्चत्वारोऽष्टकाजागतश्चमहाबृहतीमध्येचेद्यवमध्योद्वौदशकावष्ट
कास्त्यायःपंक्त्युत्तराविराट्पूर्वावा॥९॥सप्तमंजगतीजागतपदोऽष्टिनस्त्रयःस्वौचहै
महासतोबृहत्यष्टकौसप्तकःषट्कोदशकोनवकश्चैषकष्टकावामहापंक्तिः॥१०॥
अथप्रगाथाबृहतीसतोबृहत्योबार्हतःककुप्चेत्पूर्वाकाकुभोमहाबृहतीमहासतो
बृहत्योर्महाबार्हतोबृहतीविपरीतेविपरीतोत्तरोऽनुष्टुब्गायत्र्योर्वानुष्टुभोऽनुष्टुप्पु
रस्ताद्वाइत्युक्तौ॥११॥सूक्तसंख्यानुवर्ततआन्यस्याःसूक्तसंख्यायांऋषिश्चा
न्यस्मादृषेरन्वाविशिष्टस्तुहिहवेत्तछ्दविशिष्टान्यषिदैवतछंदांसिद्वित्रिचतुःपं

© Dharmartha Trust J&K. Digitized by eGangotri

प॰भा॰ चषट् सूक्तभांजि यथासंख्यमनिरुक्तासंख्याविंशतिरनादेशेत्विंद्रो देवतात्रिष्टुप् छंदः
४ प्रगाथा बार्हतोविंशिकाद्विपदाविराजस्तदर्धमेकपदाद्विर्द्विपदास्त्वचः समामनंत्यपु
श्वंसाद्विपदैवं मंडलादिष्वाग्नेयमैंद्रोत्रिष्टुबंतस्य सूक्तस्य शेषा जगत्यं आदो गायत्र्यं प्रा
ग्घिरण्यस्तूपात् ॥१२॥ गोधा घोषा विश्ववारा पालोपनिषन्निषत् ॥ ब्रह्मजाया जु
हूर्नामागस्त्यस्य स्वसादितिः ॥ इंद्राणी चेंद्रमाता च सरमा रोमशोर्वशी ॥ लोपामुद्रा
च नद्यश्च यमी नारी च शश्वती ॥ श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा ॥ रात्री रा
सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः ॥१३॥ पादा अनितगत्यां तु त्रयो द्वादशाकाः परौ ॥ अष्ट ४

© Dharmartha Trust J&K. Digitized by eGangotri

कौ शाक्वरीपादाः सप्तैवाष्टाक्षराश्च ते ॥ अतिशाक्वरपादौ द्वौ वादिनः षोडशाक्षरौ ॥ जागतौ
थाष्टकावष्टिपादाः षोडशाकास्त्रयः ॥ अष्टकौ चात्यष्टिपादौ जागतश्चाष्टकास्त्रयः ॥ ज
गतश्चाष्टकश्चाथ धृतिपादौ तु जागतौ ॥ पादास्त्रयोऽष्टकाश्चाथ षोडशाक्षर एव च ॥ अ
ष्टकश्चाथातिधृतौ जागतः षोडशाक्षरः ॥ त्रयोऽष्टका जागतश्चान्त्ये वाष्टक इत्यपि ॥ ए
वं सप्तकपादास्तु प्रसंगात्स्वयमीरिताः ॥ इति परिभाषा समाप्ता ॥ अग्निं नव मधुछंदा
वैश्वामित्रो वायो वायव्यैंद्रवायवं मैत्रावरुणास्तृचा अश्विना द्वादशाश्विनैंद्रवैश्वदेवसा
रस्वताः तृचाः सप्तैताः प्रउगदेवताः सुरूपकृत्नुं दशैंद्रं मानुयुंस्यादेहत्येनाः षण्मारुत्यो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰भा॰ वीळुचिदिंद्रेणेत्स्येष्टौचेंद्रमिदंद्रसानसिमिंद्रेहिगायंतिद्वादशानुष्टुभंविंद्रमष्टौजेता

५ माधुछंदसोग्निंद्वादशमेधातिथिःकाण्वआग्नेयमग्निनेतिपादौद्व्यग्निदेवतौनिर्मं

5 थ्याहवनीयश्चसुसमिद्धइतीध्मःसमिद्धोवाग्निस्तनूनपान्नराशंसइळोबर्हिर्देवीर्द्वा

रउषासानक्तादैव्यौहोतारौप्रचेतसौतिस्रोदेव्यःसरस्वतीळाभारत्यस्त्वष्टावनस्पतिःस्वा

हाकृतयइतिप्रत्यृचंदेवताएतदाप्रीसूक्तमेतेनान्यान्युक्तदेवतान्येकादशाकानित्वना

राशंसान्याप्रशब्दोक्तानित्वतनूनपांत्यैभिर्वैश्वदेवमिंद्रसोममरुत्वंत्स्त्रैंद्रीमारुती

त्वाष्ट्राआग्नेय्यैंद्रीमैत्रावरुणीचतस्रोद्रविणोदसआश्विन्याग्नेय्यृतुदेवताःसर्वत्रान ५

© Dharmartha Trust J&K. Digitized by eGangotri

वेंद्रावरुणयोरैंद्रावरुणंयुवाकुपादनिचनाविंद्रोफसीयसीवासोमानमितिपंचब्राह्मणस्य
स्यांश्चतुर्थ्यामिंद्रश्चसोमश्चपंचम्यादक्षिणाचान्यासादसस्पत्यानाराशंसीवांस्याप्र
नित्यमाग्निमारुतं॥१॥हरिः ॐ॥अग्निं।ईळे।पुरःऽहितं।यज्ञस्य।देवं।ऋत्विजं।होता
रं।रत्नऽधातमं॥अग्निः।पूर्वेभिः।ऋषिऽभिः।ईड्यः।नूतनैः।उत।सः।देवान्।आ।इह।वक्ष
ति॥अग्निना।रयिं।अश्नवत्।पोषं।एव।दिवेऽदिवे।यशसं।वीरवत्ऽतमं॥अग्ने।यं।य
ज्ञं।अध्वरं।विश्वतः।परिऽभूः।असि।सः।इत्।देवेषु।गच्छति॥अग्निः।होता।कविऽक्रतुः।
सत्यः।चित्रश्रवःऽतमः।देवः।देवेभिः।आ।गमत्॥३॥यत्।अंग।दाशुषे।त्वं।अग्ने।भद्रं।क

© Dharmartha Trust J&K. Digitized by eGangotri

५.९ रिष्यसि। तव। इत्। तत्। सत्यं। अंगिरः॥ उप। त्वा। अग्ने। दिवेऽदिवे। दोषाऽवस्तः। धिया। वयं। न

६ मः। भरंतः। आ। इमसि। राजंतं। अध्वराणां। गोपां। ऋतस्य। दीदिविं। वर्द्धमानं। स्वे। दमे॥

सः। नः। पिताऽइव। सूनवे। अग्ने। सुऽउपायनः। भव। सचस्व। नः। स्वस्तये॥ २॥ वायो इति।

आ। याहि। दर्शत। इमे। सोमाः। अरंऽकृताः। तेषां। पाहि। श्रुधि। हवं॥ वायो इति। उक्थेभिः।

जरंते। त्वां। अच्छ। जरितारः। सुतऽसोमाः। अहःऽविदः॥ वायो इति। तव। प्रऽपृंचती। धेना। जि

गाति। दाशुषे। उरूची। सोमऽपीतये॥ इंद्रवायू इति। इमे। सुताः। उप। प्रयःऽभिः। आ। गतं।

इंदवः। वां। उशंति। हि॥ वायो इति। इंद्रः। च। चेतथः। सुतानां। वाजिनीवसू इति। वाजिनीऽव ६

© Dharmartha Trust J&K. Digitized by eGangotri

सू। तौ। आ। यातं। उप। द्रवत्॥३॥ वायो इति। इंद्रः। च। सुन्वतः। आ। यातं। उप। निःऽकृतं। मक्षु।
इत्था। धिया। नरा॥ मित्रं। हुवे। पूतऽदक्षं। वरुणं। च। रिशादसं। धियं। घृताचीं। साधंता॥
ऋतेन। मित्रावरुणौ। ऋतऽवृधौ। ऋतऽस्पृशा। क्रतुं। बृहंतं। आशाथे इति। कवी इति। नः।
मित्रावरुणा। तुविऽजाता। उरुऽक्षया। दक्षं। दधाते इति। अपसं॥४॥ अश्विना। यज्वरीः।
इषः। द्रवत्पाणी इति द्रवत्ऽपाणी। शुभः। पती इति। पुरुऽभुजा। चनस्यतं॥ अश्विना।
पुरुऽदंससा। नरा। शवीरया। धिया। धिष्ण्या। वनतं। गिरः॥ दस्रा। युवाकवः। सुताः।
नासत्या। वृक्तऽबर्हिषः। आ। यातं। रुद्रवर्तनी इति रुद्रऽवर्तनी॥ इंद्र। आ। याहि। चित्रभा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ नोइति चित्रऽभानो।सुताः।इमे।त्वाऽयवः।अण्वीभिः।तना।पूतासः॥० इंद्र।धिया।इषितः।वि
७ प्रऽभूतः।सुतऽवतः।उप।ब्रह्माणि।वाघतः॥० इंद्रायाहि तूतुजानः।उप।ब्रह्माणि।हरिवः।
सुते।दधिष्व।नः।चनः॥५॥ ओमासः।चर्षणिऽधृतः।विश्वे।देवासः।आ।गत।दाश्वांसः।
दाशुषः।सुतं॥विश्वे।देवासः।अपऽतुरः।सुतं।आ।गंत।तूर्णयः।उस्राःऽइव।स्वसराणि
।विश्वे।देवासः।अस्रिधः।एहिऽमायासः।अद्रुहः।मेधं।जुषंत।वह्नयः॥पावका।नः।स
रस्वती।वाजेभिः।वाजिनीऽवती।यज्ञं।वष्टु।धियाऽवसुः॥चोदयित्री।सूनृतानां।चेतंती
।सुऽमतीनां।यज्ञं।दधे।सरस्वती॥महः।अर्णः।सरस्वती।प्र।चेतयति।केतुना।धियः।वि

© Dharmartha Trust J&K. Digitized by eGangotri

श्वाः । वि । राजति ॥६॥ सुरूपऽकृत्नुं । ऊतये । सुदुघांऽइव । गोऽदुहे । जुहूमसि । द्यविऽद्यवि ॥ उ
प । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब । गोऽदाः । इत् । रेवतः । मदः ॥ अथ । ते । अं
तमानां । विद्याम । सुऽमतीनां । मा । नः । अति । ख्यः । आ । गहि ॥ परा । इहि । विग्रं । अस्तृतं ।
इंद्रं । पृच्छ । विपःऽचितं । यः । ते । सखिऽभ्यः । आ । वरं ॥ उत । ब्रुवंतु । नः । निदः । निः । अन्यतः । चि
त् । आरत । दधानाः । इंद्रे । इत् । दुवः ॥७॥ उत । नः । सुऽभगान् । अरिः । वोचेयुः । दस्म । कृष्ट
यः । स्याम । इत् । इंद्रस्य । शर्मणि ॥ आ । ईं । आशुं । आशवे । भर । यज्ञऽश्रियं । नृऽमादनं । प
तयत् । मंदयत्ऽसखं ॥ अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घनः । वृत्राणां । अभवः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ प्र। आवः। वाजेषु। वाजिनं॥ तं। त्वा। वाजेषु। वाजिनं। वाजयामः। शतक्रतो इति शतऽक्रतो। ध
८ नानां। इंद्र। सातये॥ यः। रायः। अवनिः। महान्। सुऽपारः। सुन्वतः। सखा। तस्मै। इंद्राय। गा
यत॥ ८॥ आ। तु। आ। इत। नि। सीदत। इंद्रं। अभि। प्र। गायत। सखायः। स्तोमऽवाहसः॥ पु
8 रुऽतमं। पुरूणां। ईशानं। वार्याणां। इंद्रं। सोमे। सचा। सुते॥ सः। घ। नः। योगे। आ। भुवत्।
सः। राये। सः। पुरंऽध्यां। गमत्। वाजेभिः। आ। सः। नः॥ यस्य। संऽस्थे। न। वृण्वते। हरी इति।
सऽमत्ऽसु। शत्रवः। १० तस्मा इंद्राय गायत। सुतऽपाव्ने। सुताः। इमे। शुचयः। यंति। वीतये। सो
मासः। दधिऽआशिरः॥ १॥ त्वं। सुतस्य। पीतये। सद्यः। वृद्धः। अजायथाः। इंद्र। ज्येष्ठ्याय। सु ८

© Dharmartha Trust J&K. Digitized by eGangotri

ऋतो इति सुऽऋतो॥ आ। त्वा। विशंतु। आशवः। सोमासः। इंद्र। गिर्वणः। शं। ते। संतु। प्रऽचेत
से॥ त्वां। स्तोमाः। अवीवृधन्। त्वां। उक्था। शतक्रतो इति शतऽक्रतो। त्वां। वर्धंतु। नः। गि
रः॥ अक्षितऽऊतिः। सनेत्। इमं। वाजं। इंद्रः। सहस्रिणं। यस्मिन्। विश्वानि। पौंस्या॥
मा। नः। मर्ताः। अभि। द्रुहन्। तनूनां। इंद्र। गिर्वणः। ईशानः। यवय। वधं॥१०॥ युंजंति। ब्रध्नं।
अरुषं। चरंतं। परि। तस्थुषः। रोचंते। रोचना। दिवि॥ युंजंति। अस्य। काम्या। हरी इति। वि
ऽपक्षसा। रथे। शोणा। धृष्णू इति। नृऽवाहसा॥ केतुं। कृण्वन्। अकेतवे। पेशः। मर्याः। अ
पेशसे। सं। उषत्ऽभिः। अजायथाः॥ आत्। अह। स्वधां। अनु। पुनः। गर्भऽत्वं। आऽईरि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ रे। दधानाः। नाम। यज्ञियं। वीळु। चित्। आरुजत्नुऽभिः। गुहा। चित्। इंद्र। वह्निऽभिः। अविंदः।
१ उस्रियाः। अनु॥५॥ देवऽयंतः। यथा। मतिं। अछ। विदत्ऽवसुं। गिरः। महां। अनूषत।
श्रुतं। इंद्रेण। सं। हि। दक्षसे। संऽजग्मानः। अबिभ्युषा। मंदू इति। समानऽवर्चसा॥ अन
वद्यैः। अभिद्युऽभिः। मखः। सहस्वत्। अर्चति। गणैः। इंद्रस्य। काम्यैः॥ अतः। परिऽज्मन्।
आ। गहि। दिवः। वा। रोचनात्। अधि। सं। अस्मिन्। ऋंजते। गिरः। इतः। वा। सातिं। ईम
हे। दिवः। वा। पार्थिवात्। अधि। इंद्रं। महः। वा। रजसः॥१०॥ इंद्रं। इत्। गाथिनः। बृहत्।
इंद्रं। अर्केभिः। अर्किणः। इंद्रं। वाणीः। अनूषत॥ इंद्रः। इत्। हर्योः। सचा। संऽमिश्लः। आ। १

© Dharmartha Trust J&K. Digitized by eGangotri

वचःऽयुजा। इंद्रः। वज्री। हिरण्ययः॥ इंद्रः। दीर्घाय। चक्षसे। आ। सूर्यं। रोहयत्। दिवि। वि। गो
भिः। अद्रिं। ऐरयत्॥ इंद्र। वाजेषु। नः। अव। सहस्रऽप्रधनेषु। च। उग्रः। उग्राभिः। ऊतिऽभिः
इंद्रं। वयं। महाऽधने। इंद्रं। अर्भे। हवामहे। युजं। वृत्रेषु। वज्रिणं॥ १३॥ सः। नः। वृषन्। अ
मुं। चरुं। सत्राऽदावन्। अप। वृधि। अस्मभ्यं। अप्रतिऽस्कुतः॥ तुंजेऽतुंजे। ये। उत्ऽतरे। स्तोमाः
इंद्रस्य। वज्रिणः। न। विंधे। अस्य। सुऽस्तुतिं। वृषा। यूथाऽइव। वंसगः। कृष्टीः। इयर्ति। ओ ज
सा। ईशानः। अप्रतिऽस्कुतः॥ यः। एकः। चर्षणीनां। वसूनां। इरज्यति। इंद्रः। पंच। क्षितीनां॥
इंद्रं। वः। विश्वतः। परि। हवामहे। जनेभ्यः। अस्माकं। अस्तु। केवलः॥ १४॥ आ। इंद्र। सान

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. १०

सिं। रयिं। सऽजित्वानं। सदाऽसहं। वर्षिष्ठं। ऊतये। भर॥ नि। येन। मुष्टिऽहत्यया। नि। वृत्रा। रुण
धामहै। त्वाऽऊतासः। नि। अर्वता॥ इंद्र। त्वाऽऊतासः। आ। वयं। वज्रं। घना। ददीमहि। जये
म। सं। युधि। स्पृधः॥ वयं। शूरेभिः। अस्तृभिः। इंद्र। त्वया। युजा। वयं। ससह्याम। पृतन्य
तः॥ महान्। इंद्रः। परः। च। नु। महिऽत्वं। अस्तु। वज्रिणे। द्यौः। न। प्रथिना। शवः॥१५॥ संऽओहे
वा। ये। आशत। नरः। तोकस्य। सनितौ। विप्रासः। वा। धियाऽयवः॥ यः। कुक्षिः। सोमऽपा
तमः। समुद्रःऽइव। पिन्वते। उर्वीः। आपः। न। काकुदः॥ एव। हि। अस्य। सूनृता। विऽरप्शी। राम
गोऽमती। मही। पक्वा। शाखा। न। दाशुषे॥ एव। हि। ते। विऽभूतयः। ऊतयः। इंद्र। माऽवते। १०

© Dharmartha Trust J&K. Digitized by eGangotri

सद्यः। चित्। संति। दाशुषे।० एवाह्यस्य काम्या। स्तोमः। उक्थं। च। शंस्या। इंद्राय। सोमऽपीतये॥
१६॥ इंद्र। आ। इहि। मत्सि। अंधसः। विश्वेभिः। सोमपर्वऽभिः। महान्। अभिष्टिः। ओजसा॥
आ। ईं। एनं। सृजत। सुते। मंदिं। इंद्राय। मंदिने। चक्रिं। विश्वानि। चक्रये॥ मत्स्व। सुऽशि
प्र। मंदिऽभिः। स्तोमेभिः। विश्वऽचर्षणे। सच। एषु। सवनेषु। आ॥ असृग्रं। इंद्र। ते। गि
रः। प्रति। त्वां। उत्। अहासत। अजोषाः। वृषभं। पतिं॥ सं। चोदय। चित्रं। अर्वाक्। राधः।
इंद्र। वरेण्यं। असत्। इत्। ते। विऽभु। प्रऽभु॥ १७॥ अस्मान्। सु। तत्र। चोदय। इंद्र। राये। र
भस्वतः। तुविऽद्युम्न। यशस्वतः॥ सं। गोऽमत्। इंद्र। वाजऽवत्। अस्मे इति। पृथु। श्रवः। बृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ हत्। विश्वऽआयुः। धेहि। अक्षितं॥ अस्मे इति। धेहि। श्रवः। बृहत्। द्युम्नं। सहस्रऽसातमं। इंद्र।
११ ताः। रथिनीः। इषः॥ वसोः। इंद्रं। वसुऽपतिं। गीःऽभिः। गृणंतः। ऋग्मियं। होम। गंतारं। ऊतये॥
॥ सुतेऽसुते। निऽओकसे। बृहत्। बृहते। आ। इत्। अरिः। इंद्राय। शूषं। अर्चति॥ १८॥ गायं-
ति। त्वा। गायत्रिणः। अर्चंति। अर्कं। अर्किणः। ब्रह्माणः। त्वा। शतक्रतो इति शतऽक्रतो। उ-
त्। वंशंऽइव। येमिरे॥ यत्। सानोः। सानुं। आ। अरुहत्। भूरि। अस्पष्ट। कर्त्वं। तत्। इंद्रः। अ-
र्थं। चेतति। यूथेन। वृष्णिः। एजति॥ युक्ष्व। हि। केशिना। हरी इति। वृषणा। कक्ष्यऽप्रा। अथ।
नः। इंद्र। सोमऽपाः। गिरां। उपऽश्रुतिं। चर॥ आ। इहि। स्तोमान्। अभि। स्वर। अभि। गृणीहि। ११

© Dharmartha Trust J&K. Digitized by eGangotri

आ । रुव । ब्रह्म । च । नः । वसो इति । सचा । इंद्र । यज्ञं । च । वर्धय ।। उक्थं । इंद्राय । शंस्यं । वर्धनं । पुरु

निःऽसिधे । शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ।। तं । इत् । सखिऽत्वे । ईमहे । तं । रा

ये । तं । सुऽवीर्ये । सः । शक्रः । उत । नः । शकत् । इंद्रः । वसु । दयमानः ।। ६ ।। सुऽविवृतं । सुनिःऽ

अजं । इंद्र । त्वाऽदातं । इत् । यशः । गवां । अप । व्रजं । वृधि । कृणुष्व । राधः । अद्रिऽवः ।। नहि । त्वा ।

रोदसी इति । उभे इति । ऋघायमाणं । इन्वतः । जेषः । स्वःऽवतीः । अपः । सं । गाः । अस्मभ्यं ।

धूनुहि ।। आश्रुत्ऽकर्ण । श्रुधि । हवं । नु । चित् । दधिष्व । मे । गिरः । इंद्र । स्तोमं । इमं । मम । कृ

ष्व । युजः । चित् । अंतरं ।। विद्म । हि । त्वा । वृषन्ऽतमं । वाजेषु । हवनऽश्रुतं । वृषन्ऽतमस्य । हू

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ मुहे। ऊतिं। सहस्रऽसातमं। आ। तु। नः। इंद्र। कौशिक। मंदसानः। सुतं। पिब। नव्यं। आयुः। प्र। सु
१२ तिर। कृधि। सहस्रऽसां। ऋषिं॥ परि। त्वा। गिर्वणः। गिरः। इमाः। भवंतु। विश्वतः। वृद्धऽआ
युं। अनु। वृद्धयः। जुष्टाः। भवंतु। जुष्टयः॥ २०॥ इंद्रं। विश्वाः। अवीवृधन्। समुद्रऽव्यचसं। गिरः।
12 रथिऽतमं। रथिनां। वाजानां। सत्ऽपतिं। पतिं॥ सख्ये। ते। इंद्र। वाजिनः। मा। भेम। शवसः।
पते। त्वां। अभि। प्र। नोनुमः। जेतारं। अपराऽजितं॥ पूर्वीः। इंद्रस्य। रातयः। न। वि। दस्यंति। ऊ
तयः। यदि। वाजस्य। गोऽमतः। स्तोतृऽभ्यः। मंहते। मघं॥ पुरां। भिंदुः। युवा। कविः। अमितऽ
ओजाः। अजायत। इंद्रः। विश्वस्य। कर्मणः। धर्ता। वज्री। पुरुऽस्तुतः॥ त्वं। वलस्य। गोऽम १२

© Dharmartha Trust J&K. Digitized by eGangotri

नः। अप। अद्रिऽवः। अवेः। बिलं। त्वां। देवाः। अबिभ्युषः। तुज्यमानासः। आ। विषुः॥ तव। अहं। शू
रा। रातिऽभिः। प्रति। आयं। सिंधुं। आऽवदन्। उप। अतिष्ठंत। गिर्वणः। विदुः। ते। तस्य। कारवः॥
मायाभिः। इंद्र। मायिनं। त्वं। शुष्णं। अव। आतिरः। विदुष्टे तस्य॥ मेधिराः। तेषां। श्रवांसि।
उत्। तिर॥ इंद्रं। ईशानं। ओजसा। अभि। स्तोमाः। अनूषत। सहस्रं। यस्य। रातयः। उत। वा। त
संति। भूयसीः॥ २१॥ अग्निं। दूतं। वृणीमहे। होतारं। विश्वऽवेदसं। अस्य। यज्ञस्य। सुऽ
क्रतुं॥ अग्निंऽअग्निं। हवीमऽभिः। सदा। हवंत। विश्पतिं। हव्यऽवाहं। पुरुऽप्रियं॥ अग्ने।
देवान्। इह। आ। वह। जज्ञानः। वृक्तऽबर्हिषे। असि। होता। नः। ईड्यः॥ तान्। उशतः। वि। बो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ यथा। यत। अग्ने। यासि। दूत्यं। देवैः। आ। सत्सि। बर्हिषि॥ घृतऽआहवन। दीदिऽवः। प्रति।
३२ स्म। रिषतः। दह। अग्ने। त्वं। रक्षस्विनः॥ अग्निना। अग्निः। सं। इध्यते। कविः। गृहऽपतिः
13 ।युवा। हव्यऽवाट्। जुहुऽआस्यः॥ २२॥ कविं। अग्निं। उप। स्तुहि। सत्यऽधर्माणं। अध्वरे।
देवं। अमीवऽचातनं॥ यः। त्वां। अग्ने। हविःऽपतिः। दूतं। देव। सपर्यति। तस्य। स्म। प्र।
अविता। भव॥ यः। अग्निं। देवऽवीतये। हविष्मान्। आऽविवासति। तस्मै। पावक। मृ
डय॥ सः। नः। पावक। दीदिऽवः। अग्ने। देवान्। इह। आ। वह। उप। यज्ञं। हविः। च। नः॥
सः। नः। स्तवानः। आ। भर। गायत्रेण। नवीयसा। रयिं। वीरऽवतीं। इषं। अग्ने। शुक्रेण। १३

© Dharmartha Trust J&K. Digitized by eGangotri

विश्वेभिः। शोचिषा। देव। हूतिऽभिः। इमं। स्तोमं। जुषस्व। नः॥ १२॥ सुऽसमिद्धः। नः। आ। वह।
देवान्। अग्ने। हविष्मते। होतरिति। पाकं। वे। यक्षि। च॥ मधुऽमंतं। तनूऽनपात्। यज्ञं। देवेषु।
नः। कवे। अद्य। कृणुहि। वीतये॥ नराशंसं। इह। प्रियं। अस्मिन्। यज्ञे। उप। ह्वये। मधुऽजिह्वं।
हविःऽकृतं॥ अग्ने। सुखऽतमे। रथे। देवान्। ईळितः। आ। वह। असि। होता। मनुःऽहितः॥ स्तृ
णीत। बर्हिः। आनुषक्। घृतऽपृष्ठं। मनीषिणः। यत्र। अमृतस्य। चक्षणं॥ वि। श्रयंतां। ऋतऽ
वृधः। द्वारः। देवीः। असश्चतः। अद्य। नूनं। च। यष्टवे॥ २४॥ नक्तोषसा। सुऽपेशसा। अस्मि
न्। यज्ञे। उप। ह्वये। इदं। नः। बर्हिः। आऽसदे॥ ता। सुऽजिह्वा। उप। ह्वये। होतारा। दैव्या। कवीइति।

© Dharmartha Trust J&K. Digitized by eGangotri

१.प्र. यज्ञं। नः। यक्षतां। इमं॥ इळा। सरस्वती। मही। तिस्रः। देवीः। मयःऽभुवः। बर्हिः। सीदंतु। अस्रि
३५ धः॥ इह। त्वष्टारं। अग्रियं। विश्वऽरूपं। उप। ह्वये। अस्माकमस्तुकेवलः अव। सृज। वनस्पते।
15 देव। देवेभ्यः। हविः। प्र। दातुः। अस्तु। चेतनं॥ स्वाहा। यज्ञं। कृणोतन। इंद्राय। यज्वनः। गृहे॥
तत्र। देवान्। उप। ह्वये॥ २५॥ आ। एभिः। अग्ने। दुवः। गिरः। विश्वेभिः। सोमऽपीतये। देवेभिः।
याहि। यक्षि। च॥ आ। त्वा। कण्वाः। अहूषत। गृणंति। विप्र। ते। धियः। देवेभिः। अग्ने। आ। ग
हि॥ इंद्रवायू इति। बृहस्पतिं। मित्रा। अग्निं। पूषणं। भगं। आदित्यान्। मारुतं। गणं॥ प्र। वः।
भ्रियंते। इंदवः। मत्सराः। मादयिष्णवः। द्रप्साः। मध्वः। चमूऽसदः॥ ईळते। त्वां। अवस्यवः। क ३६

© Dharmartha Trust J&K. Digitized by eGangotri

ण्वासः। वृक्तऽबर्हिषः। हविष्मंतः। अरंऽकृतः॥ घृतऽपृष्ठाः। मनःऽयुजः। ये। त्वा। वहंति। वह्नयः। आ।
देवान्। सोमऽपीतये॥ २६॥ तान्। यजत्रान्। ऋतऽवृधः। अग्ने। पत्नीऽवतः। कृधि। मध्वः। सुऽ
जिह्व। पायय॥ ये। यजत्राः। ये। ईड्याः। ते। ते। पिबंतु। जिह्वया। मधोः। अग्ने। वषट्ऽकृति॥ आ। कीं।
सूर्यस्य। रोचनात्। विश्वान्। देवान्। उषःऽबुधः। विप्रः। होता। इह। वक्षति॥ विश्वेभिः। सोम्यं।
मधु। अग्ने। इंद्रेण। वायुना। पिब। मित्रस्य। धामऽभिः॥ त्वं। होता। मनुःऽहितः। अग्ने। यज्ञेषु।
सीदसि। सः। इमं। नः। अध्वरं। यज॥ युक्ष्व। हि। अरुषीः। रथे। हरितः। देव। रोहितः। ताभिः।
देवान्। इह। आ। वह॥ २७॥ इंद्र। सोमं। पिब। ऋतुना। आ। त्वा। विशंतु। इंदवः। मत्सरासः। तत्ऽ

© Dharmartha Trust J&K. Digitized by eGangotri

१.प्र. ओकसः॥ मरुतः। पिबत। ऋतुना। पोत्रात्। यज्ञं। पुनीतन। यूयं। हि। स्थ। सुऽदानवः॥ अभि। यज्ञं।
३५ गृणीहि। नः। ग्नावः। नेष्टः। पिब। ऋतुना। त्वं। हि। रत्नऽधाः। असि॥० अग्नेदेवांइहावह॥
15 सादय। योनिषु। त्रिषु। परि। भूष। पिब। ऋतुना॥ ब्राह्मणात्। इंद्र। राधसः। पिब। सोमं। ऋ
तून्। अनु। तव। इत्। हि। सख्यं। अस्तृतं॥ युवं। दक्षं। धृतऽव्रता। मित्रावरुणा। दुःऽदभं। ऋतु
ना। यज्ञं। आशाथे इति॥ रु॥ द्रविणःऽदाः। द्रविणसः। ग्रावऽहस्तासः। अध्वरे। यज्ञेषु। देवं। ई
ळते॥ द्रविणःऽदाः। ददातु। नः। वसूनि। यानि। शृण्विरे। देवेषु। ता। वनामहे॥ द्रविणःऽदाः।
पिपीषति। जुहोत। प्र। च। तिष्ठत। नेष्ट्रात्। ऋतुऽभिः। इष्यत॥ यत्। त्वा। तुरीयं। ऋतुऽभिः। द्र ३५

© Dharmartha Trust J&K. Digitized by eGangotri

विणःऽदः। यजा। महे। अध। स्म। नः। ददिः। भव।। अश्विना। पिबतं। मधु। दीद्यग्नी इति दीदिऽअग्नी

शुचिऽव्रता। ऋतुना। यज्ञऽवाहसा।। गार्हऽपत्येन। संत्य। ऋतुना। यज्ञऽनीः। असि। देवान्। दे

वऽयते। यज।। २९।। आ। त्वा। वहंतु। हरयः। वृषणं। सोमऽपीतये। इंद्र। त्वा। सूरऽचक्षसः।। इ

माः। धानाः। घृतऽस्नुवः। हरी इति। इह। उप। वक्षतः। इंद्रं। सुखऽतमे। रथे।। इंद्रं। प्रातः। हवा

महे। इंद्रं। प्रऽयति। अध्वरे। इंद्रं। सोमस्य। पीतये।। उप। नः। सुतं। आ। गहि। हरिऽभिः। इंद्र। के

शिऽभिः। सुते। हि। त्वा। हवामहे।। सः। इमं। नः। स्तोमं। आ। गहि। उप। इदं। सवनं। सुतं। गौ

रः। न। तृषितः। पिब।। ३०।। इमे। सोमासः। इंदवः। सुतासः। अधि। बर्हिषि। तान्। इंद्र। सह

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ सः। पिब। अयं। ते। स्तोमः। अग्रियः। हृदिऽस्पृक्। अस्तु। शंऽतमः। अथ। सोमं। सुतं। पिब॥ वि

१६ श्वं। इत्। सवनं। सुतं। इंद्रः। मदाय। गच्छति। वृत्रऽहा। सोमऽपीतये॥०से मन्नं॥ ७॥ कामं। आ।

पृण। गोभिः। अश्वैः। शतक्रतो इति शतऽक्रतो। स्तवाम। त्वा। सुऽआध्यः॥ ३॥ इंद्रावरुणयोः।

अहं। सम्ऽराजोः। अवः। आ। वृणे। ता। नः। मृळातः। ईदृशे॥ गंतारा। हि। स्थः। अवसे। हवं। वि

प्रस्य। माऽवतः। धर्तारा। चर्षणीनां॥ अनुऽकामं। तर्पयेथां। इंद्रावरुणा। रायः। आ। ता। वां।

नेदिष्ठं। ईमहे॥ युवाकु। हि। शचीनां। युवाकु। सुऽमतीनां। भूयाम। वाजऽदाव्नां॥ इंद्रः। सह

स्रऽदाव्नां। वरुणः। शंस्यानां। क्रतुः। भवति। उक्थ्यः॥ ३॥ तयोः। इत्। अवसा। वयं। सनेम। १६

© Dharmartha Trust J&K. Digitized by eGangotri

नि। चु। धीमहि। स्यात्। उत। प्रऽरेचनं॥ इंद्रावरुणा। वां। अहं। हुवे। चित्राय। राधसे। अस्मान्। सु।
२ जिग्युषः। कृतं। इंद्रावरुणा। नु। नु। वां। सिसासंतीषु। धीषु। आ। अस्मभ्यं। शर्म। यच्छतं॥ प्र। वां।
अश्नोतु। सुऽस्तुतिः। इंद्रावरुणा। यां। हुवे। यां। ऋधाथे। इति। सधऽस्तुतिं॥ ३३॥ सोमानं। स्वर
णं। कृणुहि। ब्रह्मणः। पते। कक्षीवंतं। यः। औशिजः॥ यः। रेवान्। यः। अमीवऽहा। वसुऽवित्।
पुष्टिऽवर्धनः। सः। नः। सिसक्तु। यः। तुरः॥ मा। नः। शंसः। अररुषः। धूर्तिः। प्रणक्। मर्त्य
स्य। रक्ष। नः। ब्रह्मणः। पते॥ सः। घ। वीरः। न। रिष्यति। यं। इंद्रः। ब्रह्मणः। पतिः। सोमः। हिनोति।
मर्त्यं॥ त्वं। तं। ब्रह्मणः। पते। सोमः। इंद्रः। च। मर्त्यं। दक्षिणा। पातु। अंहसः॥ ३४॥ सदसः। प

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. नि। अद्भुतं। प्रियं। इंद्रस्य। काम्यं। सनिं। मेधां। अयासिषं॥ यस्मात्। ऋते। न। सिध्यति। यज्ञः।
३८ विपः ऽचितः। चन। सः। धीनां। योगं। इन्वति॥ आत्। ऋध्नोति। हविः ऽकृतिं। प्रांचं। कृणोति। अ
ध्वरं। होत्रा। देवेषु। गच्छति॥ नराशंसं। सुऽधृष्टमं। अपश्यं। सप्रथः ऽतमं। दिवः। न। सद्मऽम
खसं॥ ३५॥ प्रति। त्यं। चारुं। अध्वरं। गोऽपीथाय। प्र। हूयसे। मरुत्ऽभिः। अग्ने। आ। गहि। न
हि। देवः। न। मर्त्यः। महः। तव। क्रतुं। परः।० मरुद्भिरग्नआगहि। ये। महः। रजसः। विदुः। विश्वे। देवासः।
अद्रुहः।० मरुद्भिरग्नआगहि। ये। उग्राः। अर्कं। आनृचुः। अनाधृष्टासः। ओजसा।० मरुद्भिरग्नआगहि
ये। शुभ्राः। घोरऽवर्पसः। सुऽक्षत्रासः। रिशादसः।० मरुद्भिरग्नआगहि॥ ३६॥ ये। नाकस्य। अधि। ३८

17

© Dharmartha Trust J&K. Digitized by eGangotri

रोचने। दिवि। देवासः। आसते। ० ये। ईङ्खयन्ति। पर्वतान्। तिरः। समुद्रं। अर्णवं। ० आ। ये। तन्वन्ति।
रश्मिऽभिः। तिरः। समुद्रं। ओजसा। ० अभि। त्वा। पूर्वऽपीतये। सृजामि। सोम्यं। मधु। ०।। ३७।।
इति प्रथमाष्टके प्रथमोध्यायः।। ॐ।। अयमष्टावार्भवमिहषट्कैंद्राग्नं प्रातर्युजा सेकाचत
स्त्र आश्विन्यस्तथा सावित्र्य आग्नेय्यो द्वे देवीनामेकैकैंद्राणी वरुणान्यग्नायीनां द्यावापृ
थिव्येपार्थिवी षड्वैष्णव्यास्तो देव्यो देवीर्वानीव्राश्चतुर्विंशतिर्वायव्यैकैंद्रवायव्यौ मैत्रावरुण
मरुत्वतीयवैश्वदेवपौष्णास्तृचाः शिष्टा आप्यौ त्याध्यधर्याग्नेय्यः प्रउगं नः पुरउष्णिक्ककुप्परानु
ष्टुभिस्त्र्यश्वा त्याएककविंशतीप्रतिष्ठा ककुप्पंचो नाजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो

© Dharmartha Trust J&K. Digitized by eGangotri

प·स· देवरातोवारुणंतुत्रैष्टुभंमारोकाष्याग्नेय्यौसावित्रस्तृचोगायत्र्यौस्यांस्याभागीवांयज्ञिसेका
३८ वसिष्ठदृशोग्नेयंत्वंश्वंसप्तोनागायत्रंस्यांदेवीत्रिष्टुब्व्यात्रग्ना॰वानवषकनुष्टुबादियज्ञि
ध्यौलूखल्यौपरेमोसल्यौचप्रजापतेर्हरिश्चंद्रस्यौसाचर्मप्रशंसावांयज्ञिंसप्तपांक्तमावा सि
18 ध्युधिकास्माकंपादनिचृत्कश्वत्रिष्टुप्परोतचावाश्विनोषस्यौत्वमग्नेशूनाहिरण्यस्तू
पआंगिरसआग्नेयंत्रिष्टुवंस्याष्टमीषाळ्कस्यौचेंद्रस्यपंचोना॥२॥ॐ॥अयंदेवाय।
जन्मने।स्तोमः।विप्रेभिः।आसया।अकारि।रत्नऽधातमः॥ये।इंद्राय।वचःऽयुजा।तत
क्षुः।मनसा।हरी इति।शमीभिः।यज्ञं।आशत॥तक्षन्।नासत्याभ्यां।परिऽज्मानं।सुऽखं। १८

© Dharmartha Trust J&K. Digitized by eGangotri

रथं। तक्षन्। धेनुं। सबःऽदुघां॥ युवाना। पितरा। पुनरिति। सत्यऽमंत्राः। ऋजुऽयवः। ऋभवः। वि

ष्टी। अक्रत॥ सं। वः। मदासः। अग्मत। इंद्रेण। च। मरुत्वता। आदित्येभिः। च। राजऽभिः॥ उत। त्यं।

चमसं। नवं। त्वष्टुः। देवस्य। निःऽकृतं। अकर्त। चतुरः। पुनरिति॥ ते। नः। रत्नानि। धत्तन। त्रिः।

आ। साप्तानि। सुन्वते। एकंऽएकं। सुशस्तिऽभिः॥ अधारयंत। वह्नयः। अभजंत। सुऽकृत्यया।

भागं। देवेषु। यज्ञियं॥ २॥ इह। इंद्राग्नी इति। उप। ह्वये। तयोः। इत्। स्तोमं। उश्मसि। ता। सोमं। सो

मऽपातमा॥ ता। यज्ञेषु। प्र। शंसत। इंद्राग्नी इति। शुंभत। नरः। ता। गायत्रेषु। गायत॥ ता। मित्र

स्य। प्रऽशस्तये। इंद्राग्नी इति। ता। हवामहे। सोमऽपा। सोमऽपीतये। उग्रा। संता। हवामहे। उप।

© Dharmartha Trust J&K. Digitized by eGangotri

प०प्र० इह। सवनं। सुतं। इंद्राग्नी इति। आ। इह। गच्छतं॥ ता। महांतं। सदस्पती इति। इंद्राग्नी इति। रक्षः।
१९ उब्जतं। अप्रजाः। संतु। अत्रिणः॥ तेन। सत्येन। जागृतं। अधि। प्रऽचेतुने। पदे। इंद्राग्नी इति। श
र्म। यच्छतं॥ ३॥ प्रातःऽयुजा। वि। बोधय। अश्विनौ। आ। इह। गच्छतां। अस्य। सोमस्य। पीतये॥
या। सुऽरथा। रथिऽतमा। उभा। देवा। दिविऽस्पृशा। अश्विना। ता। हवामहे॥ या। वां। कशा। म
धुऽमती। अश्विना। सूनृताऽवती। तया। यज्ञं। मिमिक्षतं॥ नहि। वां। अस्ति। दूरके। यत्र। रथेन।
गच्छथः॥ अश्विना। सोमिनः। गृहं॥ हिरण्यऽपाणिं। ऊतये। सवितारं। उप। ह्वये। सः। चेत्ता।
देवता। पदं॥ ४॥ अपां। नपातं। अवसे। सवितारं। उप। स्तुहि। तस्य। व्रतानि। उश्मसि॥ विऽभ १९

© Dharmartha Trust J&K. Digitized by eGangotri

क्तारं। हवामहे। वसोः। चित्रस्य। राधसः। सवितारं। नृऽचक्षसं॥ सखायः। आ। नि। सीदत।
सविता। स्तोम्यः। नु। नः। दाता। राधांसि। शुंभति॥ अग्ने। पत्नीः। इह। आ। वह। देवानां। उ
शतीः। उप। त्वष्टारं। सोमऽपीतये॥ आ। ग्नाः। अग्ने। इह। अवसे। होत्रां। यविष्ठ। भारतीं। व
रूत्रीं। धिषणां। वह॥ अभि। नः। देवीः। अवसा। महः। शर्मणा। नृऽपत्नीः। अच्छिन्नऽपत्राः।
सचंतां॥ इह। इंद्राणीं। उप। ह्वये। वरुणानीं। स्वस्तये। अग्नायीं। सोमऽपीतये॥ मही। द्यौः।
पृथिवी। च। नः। इमं। यज्ञं। मिमिक्षतां। पिपृतां। नः। भरीमऽभिः॥ तयोः। इत्। घृतऽवत्। प
यः। विप्राः। रिहंति। धीतिऽभिः। गंधर्वस्य। ध्रुवे। पदे॥ स्योना। पृथिवि। भव। अनृक्षरा। नि॰

© Dharmartha Trust J&K. Digitized by eGangotri

प॰म॰ वेशनी। यच्छ। नः। शर्म। सऽप्रथः॥६॥ अतः। देवाः। अवंतु। नः। यतः। विष्णुः। विऽचक्रमे। पृथिव्याः। स
२० प्त। धामऽभिः॥ इदं। विष्णुः। वि। चक्रमे। त्रेधा। नि। दधे। पदं। संऽऊळ्हं। अस्य। पांसुरे॥ त्रीणि। पदा।
20 वि। चक्रमे। विष्णुः। गोपाः। अदाभ्यः॥ अतः। धर्माणि। धारयन्॥ विष्णोः। कर्माणि। पश्यत। य
तः। व्रतानि। पस्पशे। इंद्रस्य। युज्यः। सखा॥ तत्। विष्णोः। परमं। पदं। सदा। पश्यंति। सूरयः।
दिविऽइव। चक्षुः। आऽततं॥ तत्। विप्रासः। विपन्यवः। जागृऽवांसः। सं। इंधते। विष्णोः। यत्।
परमं। पदं॥७॥ तीव्राः। सोमासः। आ। गहि। आशीःऽवंतः। सुताः। इमे। वायो इति। तान्। प्रऽ
स्थितान्। पिब॥ उभा। देवा। दिविऽस्पृशा। इंद्रवायू इति। हवामहे। ० अस्य सोमस्य पीतये॥ इंद्र २०

© Dharmartha Trust J&K. Digitized by eGangotri

वायू इति। मनःऽजुवा। विप्राः। हवंते। ऊतये। सहस्रऽअक्षा। धियः। पती इति॥ मित्रं। वयं। हवा

महे। वरुणं। सोमऽपीतये। जज्ञाना। पूतऽदक्षसा॥ ऋतेन। यौ। ऋतऽवृधौ। ऋतस्य। ज्योतिषः।

पती इति॥ ता। मित्रावरुणा। हुवे॥ २॥ वरुणः। प्रऽअविता। भुवत्। मित्रः। विश्वाभिः। ऊतिऽभिः।

करतां। नः। सुऽराधसः॥ मरुत्वंतं। हवामहे। इंद्रं। आ। सोमऽपीतये। सऽजूः। गणेन। तृंपतु॥

इंद्रऽज्येष्ठाः। मरुत्ऽगणाः। देवासः। पूषऽरातयः। विश्वे। मम। श्रुत। हवं॥ हत। वृत्रं। सुऽदा

नवः। इंद्रेण। सहसा। युजा। मा। नः। दुःऽशंसः। ईशत॥ विश्वान्। देवान्। हवामहे। मरुतः।

सोमऽपीतये। उग्राः। हि। पृश्निऽमातरः॥ ३॥ जयतांऽइव। तन्यतुः। मरुतां। एति। धृष्णुऽया।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰

२१

21

यत। शुभ्रं। याथन। नरः॥ हस्कारात्। विऽद्युतः। परि। अतः। जाताः। अवंतु। नः। मरुतः। मृळयंतु। नः॥
आ। पूषन्। चित्रऽबर्हिषं। आघृणे। धरुणं। दिवः। आ। अज। नष्टं। यथा। पशुं॥ पूषा। राजानं।
आघृणिः। अपऽगूळ्हं। गुहा। हितं। अविंदत्। चित्रऽबर्हिषं॥ उतो इति। सः। मह्यं। इंदुऽभिः। षट्।
युक्तान्। अनुऽसेसिधत्। गोभिः। यवं। न। चर्कृषत्॥ १०॥ अंबयः। यंति। अध्वऽभिः। जामयः।
अध्वरिऽयतां। पृंचतीः। मधुना। पयः॥ अमूः। याः। उप। सूर्ये। याभिः। वा। सूर्यः। सह। ताः। नः।
हिन्वंतु। अध्वरं॥ अपः। देवीः। उप। ह्वये। यत्र। गावः। पिबंति। नः। सिंधुऽभ्यः। कर्त्वं। हविः॥ अ
प्ऽसु। अंतः। अमृतं। अप्ऽसु। भेषजं। अपां। उत। प्रऽशस्तये। देवाः। भवत। वाजिनः॥ अप्ऽसु। २१

© Dharmartha Trust J&K. Digitized by eGangotri

मे। सोमः। अब्रवीत्। अंतः। विश्वानि। भेषजा। अग्निं। च। विश्वऽशंभुवं। आपः। च। विश्वऽभेषजीः
॥११॥ आपः। पृणीत। भेषजं। वरूथं। तन्वे। मम। ज्योक्। च। सूर्यं। दृशे॥ इदं। आपः। प्र। वहत।
यत्। किं। च। दुःऽइतं। मयि। यत्। वा। अहं। अभिऽदुद्रोह। यत्। वा। शेपे। उत। अनृतं॥ आपः।
अद्य। अनु। अचारिषं। रसेन। सं। अगस्महि। पयस्वान्। अग्ने। आ। गहि। तं। मा। सं। सृज।
वर्चसा॥ सं। मा। अग्ने। वर्चसा। सृज। सं। प्रऽजया। सं। आयुषा। विद्युः। मे। अस्य। देवाः। इं
द्रः। विद्यात्। सह। ऋषिऽभिः॥३२॥ कस्य। नूनं। कतमस्य। अमृतानां। मनामहे। चारु। देव
स्य। नाम। कः। नः। मह्यै। अदितये। पुनः। दात्। पितरं। च। दृशेयं। मातरं। च॥ अग्नेः। वयं। प्र

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ऋ॰ थमस्य। अमृतानां। मनामहे। चारु। देवस्य। नाम। कः। नः। मह्यै। अदितये। पुनः। दात्। पितरं।
२२ च। दृशेयं। मातरं। च॥ अभि। त्वा। देव। सवितः। ईशानं। वार्याणां। सदा। अवन्। भागं। ईम
22 हे। यः। चित्। हि। ते। इत्था। भगः। शशमानः। पुरा। निदः। अद्वेषः। हस्तयोः। दधे॥ भगऽभक्त
स्य। ते। वयं। उत्। अशेम। तव। अवसा। मूर्धानं। रायः। आऽरभे॥ ५॥ नहि। ते। क्षत्रं। न। स
हः। न। मन्युं। वयः। चन। अमी इति। पतयंतः। आपुः। न। इमाः। आपः। अनिऽमिषं। चरंतीः।
न। ये। वातस्य। प्रऽमिनंति। अभ्वं॥ अबुध्ने। राजा। वरुणः। वनस्य। ऊर्ध्वं। स्तूपं। ददते। पूतऽ
दक्षः। नीचीनाः। स्थुः। उपरि। बुध्नः। एषां। अस्मे इति। अंतः। निऽहिताः। केतवः। स्युरिति स्युः॥ २२

© Dharmartha Trust J&K. Digitized by eGangotri

उरुं । हि । राजा । वरुणः । चकार । सूर्याय । पंथां । अनुऽएतवै । ऊं इति । अपदे । पादा । प्रतिऽधातवे । अ

कः । उत । अपऽवक्ता । हृदयऽविधः । चित् ॥ शतं । ते । राजन् । भिषजः । सहस्रं । उर्वी । गभीरा ।

सुऽमतिः । ते । अस्तु । बाधस्व । दूरे । निःऽऋतिं । पराचैः । कृतं । चित् । एनः । प्र । मुमुग्धि । अस्म

त् । अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तं । ददृश्रे । कुह । चित् । दिवा । ईयुः । अदब्धा

नि । वरुणस्य । व्रतानि । विऽचाकशत् । चंद्रमाः । नक्तं । एति ॥ १४ ॥ तत् । त्वा । यामि । ब्रह्मणा ।

वंदमानः । तत् । आ । शास्ते । यजमानः । हविःऽभिः । अहेळमानः । वरुण । इह । बोधि । उरुऽ

शंस । मा । नः । आयुः । प्र । मोषीः ॥ तत् । इत् । नक्तं । तत् । दिवा । मह्यं । आहुः । तत् । अयं । केतः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ हृदः। आ। चि। केत। शुनःशेपः। यं। अह्वत्। गृभीतः। सः। अस्मान्। राजा। वरुणः। मुमोक्तु। शुनः-

२२ शेपः। हि। अह्वत्। गृभीतः। त्रिषु। आदित्यं। द्रुऽपदेषु। बद्धः। अव। एनं। राजा। वरुणः। सस-

ऽज्यात्। विद्वान्। अदब्धः। वि। मुमोक्तु। पाशान्। अव। ते। हेळः। वरुण। नमःऽभिः। अव।

23 यज्ञेभिः। ईमहे। हविःऽभिः। क्षयन्। अस्मभ्यं। असुर। प्रचेत इति प्रऽचेतः। राजन्। एनांसि। शि-

श्रथः। कृतानि॥ उत्। उत्ऽतमं। वरुण। पाशं। अस्मत्। अव। अधमं। वि। मध्यमं।

श्रथय। अथ। वयं। आदित्य। व्रते। तव। अनागसः। अदितये। स्याम॥ १५॥ यत्। चित्।

हि। ते। विशः। यथा। प्र। देव। वरुण। व्रतं। मिनीमसि। द्यविऽद्यवि॥ मा। नः। वधाय। हत्नवे। २३

© Dharmartha Trust J&K. Digitized by eGangotri

जिहीळानस्य। रीरधः। मा। हृणानस्य। मन्यवे॥ वि। मृळीकाय। ते। मनः। रथीः। अश्वं। न। संऽदि

मे। तं। गीःऽभिः। वरुण। सीमहि॥ परा। हि। विऽमन्यवः। पतंति। वस्यःऽइष्टये। वयः। न। वसतीः। उ

प॥ कदा। क्षत्रऽश्रियं। नरं। आ। वरुणं। करामहे। मृळीकाय। उरुऽचक्षसं॥ऽध्या। तत्। इत्। स

मानं। आशाते इति। वेनंता। न। प्र। युच्छतः। धृतऽव्रताय। दाशुषे॥ वेद। यः। वीनां। पदं। अंतरि

क्षेण। पततां। वेद। नावः। समुद्रियः॥ वेद। मासः। धृतऽव्रतः। द्वादश। प्रजाऽवतः। वेद। यः। उ

पऽजायते॥ वेद। वातस्य। वर्तनिं। उरोः। ऋष्वस्य। बृहतः। वेद। ये। अधिऽआसते॥ नि। ससा

द। धृतऽव्रतः। वरुणः। पस्त्यासु। आ। सांऽराज्याय। सुऽक्रतुः॥ १०॥ अतः। विश्वानि। अद्भु

© Dharmartha Trust J&K. Digitized by eGangotri

पप्र॰ ता। चिकित्वान्। अभि। पश्यति। कृतानि। या। च। कर्त्वा॥ सः। नः। विश्वाहा। सुऽक्रतुः। आदित्यः।
२५ सुऽपथा। करत्। प्र। नः। आयूंषि। तारिषत्॥ बिभ्रत्। द्रापिं। हिरण्ययं। वरुणः। वस्त। निःऽनि
जं। परि। स्पशः। नि। सेदिरे॥ न। यं। दिप्सन्ति। दिप्सवः। न। द्रुह्वाणः। जनानां। न। देवं। अभिऽ
24 मातयः। उत। यः। मानुषेषु। आ। यशः। चक्रे। असामि। आ। अस्माकं। उदरेषु। आ॥ १८॥ प
रा। मे। यन्ति। धीतयः। गावः। न। गव्यूतीः। अनु। इच्छन्तीः। उरुऽचक्षसं॥ सं। नु। वोचावहै। पुनः।
यतः। मे। मधु। आऽभृतं। होताऽइव। क्षदसे। प्रियं॥ दर्शं। नु। विश्वऽदर्शतं। दर्शं। रथं। अधि।
क्षमि। एताः। जुषत। मे। गिरः॥ इमं। मे। वरुण। श्रुधि। हवं। अद्य। च। मृळय। त्वां। अवस्युः। आ। २५

© Dharmartha Trust J&K. Digitized by eGangotri

जीवसे।

चके॥ त्वं। विश्वस्य। मेधिर। दिवः। च। ग्मः। च। राजसि। सः। यामनि। प्रति। श्रुधि। उत्। उत्ऽतमं।
मुमुग्धि। नः। वि। पाशं। मध्यमं। चृत। अव। अधमानि। २१॥ वसिष्व। हि। मियेध्य। वस्त्राणि।
ऊर्जां। पते। ० सेमं नो अध्वरं यज। नि। नः। होता। वरेण्यः। सदा। यविष्ठ। मन्मऽभिः। अग्ने। दि-
विऽमता। वचः॥ आ। हि। स्म। सूनवे। पिता। आपिः। यजति। आपये। सखा। सख्ये। वरेण्यः॥
आ। नः। बर्हिः। रिशादसः। वरुणः। मित्रः। अर्यमा। सीदंतु। मनुषः। यथा॥ पूर्व्य। होतः। अस्य।
नः। मंदस्व। सख्यस्य। च। इमाः। ऊं इति। सु। श्रुधि। गिरः॥ २०॥ ० यच्चिद्धि शश्वता। तना। देवं-
ऽदेवं। यजामहे। त्वे इति। इत्। हूयते। हविः॥ प्रियः। नः। अस्तु। विश्पतिः। होता। मंद्रः। वरेण्यः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.भ्र. प्रियाः । सुऽअग्नयः । वयं । । सुऽअग्नयः । हि । वार्यं । देवासः । दधिरे । च । नः । सुऽअग्नयः ।
२५ मनामहे । अथ । नः । उभयेषां । अमृत । मर्त्यानां ॥ मिथः । सन्तु । प्रऽशस्तयः ॥ विश्वेभिः । अग्ने ।
25 अग्निऽभिः । इमं । यज्ञं । इदं । वचः । चनः । धाः । सहसः । यहो इति ॥ २३ ॥ अश्वं । न । त्वा । वारऽ
वन्तं । वन्दध्यै । अग्निं । नमःऽभिः । सम्ऽराजन्तं । अध्वराणां ॥ सः । घ । नः । सूनुः । शवसा । पृथुऽ
प्रगामा । सुऽशेवः । मीढ्वान् । अस्माकं । बभूयात् ॥ सः । नः । दूरात् । च । आसात् । च । नि ।
मर्त्यात् । अघऽयोः । पाहि । सदं । इत् । विश्वऽआयुः ॥ इमं । ऊं इति । सु । अस्माकं । सनिं । स्वां
गायत्रं । नव्यांसं । अग्ने । देवेषु । प्र । वोचः ॥ आ । नः । भज । परमेषु । आ । वाजेषु । मध्यमे २५

© Dharmartha Trust J&K. Digitized by eGangotri

पु। शिक्षा। वसुः। अंतमस्य॥२२॥ विऽभक्ता। असि। चित्रभानो इति चित्रऽभानो। सिंधोः। ऊर्मौ। उपाके।
आ। सद्यः। दाशुषे। क्षरसि॥ यं। अग्ने। पृत्ऽसु। मर्त्यं। अवाः। वाजेषु। यं। जुनाः। सः। यंता। शश्वतीः। इषः।
नकिः। अस्य। सहंत्य। परिऽएता। कयस्य। चित्। वाजः। अस्ति। श्रवाय्यः॥ सः। वाजं। विश्वऽचर्षणिः।
अर्वत्ऽभिः। अस्तु। तरुता। विप्रेभिः। अस्तु। सनिता॥ जराऽबोध। तत्। विविड्ढि। विशेऽविशे। यज्ञिया
य। स्तोमं। रुद्राय। दृशीकं॥२३॥ सः। नः। महान्। अनिऽमानः। धूमऽकेतुः। पुरुऽचंद्रः। धियें। वाजाय। हिन्व
तु॥ सः। रेवान्ऽइव। विश्पतिः। दैव्यः। केतुः। शृणोतु। नः। उक्थैः। अग्निः। बृहत्ऽभानुः॥ नमः। मह
त्ऽभ्यः। नमः। अर्भकेभ्यः। नमः। युवऽभ्यः। नमः। आशिनेभ्यः। यजाम। देवान्। यदि। शक्न

© Dharmartha Trust J&K. Digitized by eGangotri

प॰त्र॰ वा।मा।मा।ज्यायसः।शंसं।आ।रुक्षि।देवाः।२८।। यत्र।ग्रावा।पृथुऽबुध्नः।ऊर्ध्वः।भवति।सोत
२६ वे।उलूखलऽसुतानां।अव।इत्।ऊं इति।इंद्र।जल्गुलः।। यत्र।द्वौऽइव।जघना।अधिऽसव
26 न्या।कृता।० उलूखलसुताना।यत्र।नारी।अपऽच्यवं।उपऽच्यवं।च।शिक्षते।० यत्र।मंथां।
विऽबध्नते।रश्मीन्।यमितवेऽइव।० यत्।चित्।हि।त्वं।गृहेऽगृहे।उलूखलक।युज्यसे।
इह।द्युमत्ऽतमं।वद।जयतांऽइव।दुंदुभिः।।२९।। उत।स्म।ते।वनस्पते।वातः।वि।वाति।
अग्रं।इत्।अथो इति।इंद्राय।पातवे।सुनु।सोमं।उलूखल।। आयजी इत्याऽयजी।वाज
ऽसातमा।ता।हि।उच्चा।विऽजर्भृतः।हरी इवेति हरीऽइव।अंधांसि।बप्सता।।ता।नः २६

अद्य। वनस्पती इति। ऋष्वौ। ऋष्वेभिः। सोतृऽभिः। इन्द्राय। मधुऽमत्। सुतम्॥ उत्ऽशिष्टम्। चम्वोः।
भर। सोमम्। पवित्रे। आ। सृज। नि। धेहि। गोः। अधि। त्वचि॥ २८॥ ० यच्चिद्धि सत्य। सोमऽपाः।
अनाशस्ताःऽइव। स्मसि। ० आ तू न इंद्र शंसय। गोषु। अश्वेषु। शुभ्रिषु। सहस्रेषु। तुविऽमघ।
शिप्रिन्। वाजानाम्। पते। शचीऽवः। तव। दंसना॥ ० नि। स्वापय। मिथुऽदृशा। सस्ताम्। अबुध्य
माने इति। ० ससन्तु। त्याः। अरातयः। बोधन्तु। शूर। रातयः। ० सम्। इन्द्र। गर्दभम्। मृण। नुवन्तम्।
पापया। अमुया। ० पताति। कुण्डृणाच्या। दूरम्। वातः। वनात्। अधि। ० सर्वम्। परिऽक्रोशम्। जहि।
जम्भय। कृकदाश्वम्। ०॥ २९॥ आ। वः। इन्द्रम्। क्रिविम्। यथा। वाजऽयन्तः। शतऽक्रतुम्। मंहिष्ठम्।

© Dharmartha Trust J&K. Digitized by eGangotri

सिञ्चे। इन्दुऽभिः॥ शतं। वा। यः। शुचीनां। सहस्रं। वा। संऽआशिरां। आ। इत्। नु। ऊं इति। निम्नं। न। रीयते॥ सं।
यत्। मदाय। शुष्मिणे। एना। हि। अस्य। उदरे। समुद्रः। न। व्यचः। दधे। अयं। ऊं इति। ते। सं। अतसि। कपो
तःऽइव। गर्भऽधिं। वचः। तत्। चित्। नः। ओहसे॥ स्तोत्रं। राधानां। पते। गिर्वाहः। वीर। यस्य। ते। विऽभू
तिः। अस्तु। सूनृता॥ २८॥ ऊर्ध्वः। तिष्ठ। नः। ऊतये। अस्मिन्। वाजे। शतक्रतो इति शतऽक्रतो। सं। अन्येषु।
ब्रवावहै॥ योगेऽयोगे। तवःऽतरं। वाजेऽवाजे। हवामहे। सखायः। इन्द्रं। ऊतये॥ आ। घ। गमत्। यदि। श्रव
त्। सहस्रिणीभिः। ऊतिऽभिः। वाजेभिः। उप। नः। हवं॥ अनु। प्रत्नस्य। ओकसः। हुवे। तुविऽप्रतिं। नरं। यं। ते।
पूर्वं। पिता। हुवे॥ तं। त्वा। वयं। विश्वऽवार। आ। शास्महे। पुरुऽहूत। सखे। वसो इति। जरितृऽभ्यः॥ २९॥ अ २७

© Dharmartha Trust J&K. Digitized by eGangotri

कृणोः। अक्षं। न। चक्र्योः॥ आँ यत्। दुवः। शतक्रतो इति शतऽक्रतो। आ। कामं। जरितॄणां।

स्माकं। शिप्रिणीनां। सोमऽपाः। सोमऽपानां। सखे। वज्रिन्। सखीनां॥ तथा। तत्। अस्तु। सोमऽ

पाः। सखे। वज्रिन्। तथा। कृणु। यथा। ते। उश्मसि। इष्टये॥ रेवतीः। नः। सधऽमादे। इंद्रे। संतु।

तुविऽवाजाः। क्षुऽमंतः। याभिः। मदेम॥ आ। घ। त्वाऽवान्। त्मना। आप्तः। स्तोतृऽभ्यः। धृष्णो इति।

धृष्णो। इयानः। ऋणोः। अक्षं। न। शचीभिः॥ २०॥ शश्वत्। इंद्रः। पोप्रुथत्ऽभिः। जिगाय। नानदत्ऽभिः।

शाश्वसत्ऽभिः। धनानि॥ सः। नः। हिरण्यऽरथं। दंसनाऽवान्। सः। नः। सनिता। सनये। सः। नः। अ

दात्॥ आ। अश्विना। अश्वऽवत्या। इषा। यातं। शवीरया। गोऽमत्। दस्रा। हिरण्यऽवत्॥ समान

ऽयोजनः। हि। वां। रथः। दस्रौ। अमर्त्यः। समुद्रे। अश्विना। ईयते॥ नि। अघ्न्यस्य। मूर्धनि। चक्रं।

© Dharmartha Trust J&K. Digitized by eGangotri

१.प्र. रथस्य।येमथुः।परि।यां।अन्यत्।ईयते॥कः।नौ।तुषः।कधऽप्रियो।भुजे।मर्तः।अमर्त्यो।कं।नक्ष
२८ सो।विभाऽवरि।वयं।हि।ते।अमन्महि।आ।अंतात्।आ।पराकात्।अश्वे।न।चित्रे।अरुषि॥
त्वं।त्येभिः।आ।गहि।वाजेभिः।दुहितः।दिवः।अस्मे इति।रयिं।नि।धारय॥३१॥ त्वं।अग्ने।
28 प्रथमः।अंगिराः।ऋषिः।देवः।देवानां।अभवः।शिवः।सखा।तव।व्रते।कवयः।विपनाऽ
अपसः।अजायंत।मरुतः।भ्राजत्ऽऋष्टयः।० त्वमग्ने प्रथमो।अंगिरःऽतमः।।कविः।देवानां।
परि।भूषसि।व्रतं।विऽभुः।विश्वस्मै।भुवनाय।मेधिरः।द्विऽमाता।शयुः।कतिधा।चित्।आ
यवे।० त्वमग्ने प्रथमो।मातरिश्वने।आविः।भव।सुक्रतुऽया।विवस्वते।अरेजेतां।रोदसी २८

© Dharmartha Trust J&K. Digitized by eGangotri

इति। होतऽवूर्यै। असघ्नोः। भारं। अयजः। महः। वसो इति॥ त्वं। अग्ने। मनवे। द्यां। अवाशयः। पु
रूरवसे। सुऽकृते। सुकृतऽतरः। श्वात्रेण। यत्। पित्रोः। मुच्यसे। परि। आ। त्वा। पूर्वं। अनयन्।
आ। अपरं। पुनरिति॥ त्वं। अग्ने। वृषभः। पुष्टिऽवर्धनः। उद्यतऽस्रुचे। भवसि। श्रवाय्यः। यः।
आऽहुतिं। परि। वेद। वषट्ऽकृतिं। एकऽआयुः। अग्रे। विशः। आऽविवाससि॥ ३२॥ त्वं। अग्ने।
वृजिनऽवर्तनिं। नरं। सक्मन्। पिपर्षि। विदथे। विऽचर्षणे। यः। शूरऽसाता। परिऽतक्म्ये। धनेदृ
भेभिः। चित्। समृता। हंसि। भूयसः॥ त्वं। तं। अग्ने। अमृतऽत्वे। उत्ऽतमे। मर्तं। दधासि। श्रव
से। दिवेऽदिवे। यः। ततृषाणः। उभयाय। जन्मने। मयः। कृणोषि। प्रयः। आ। च। सूरये॥ त्वं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ नः। अग्ने। सनये। धनानां। यशसं। कारुं। कृणुहि। स्तवानः। ऋध्याम। कर्म। अपसा। नवेन।
२९ देवैः। द्यावापृथिवी इति। प्र। अवतं। नः। ०। त्वं। नः। अग्ने। पित्रोः। उपऽस्थे। आ। देवः। देवेषु। अनव
द्य। जागृविः। तनूऽकृत्। बोधि। प्रऽमतिः। च। कारवे। त्वं। कल्याण। वसु। विश्वं। आ। ऊपिषे॥
29 त्वं। अग्ने। प्रऽमतिः। त्वं। पिता। असि। नः। त्वं। वयःऽकृत्। तव। जामयः। वयं। सं। त्वा। रायः। श
तिनः। सं। सहस्रिणः। सुऽवीरं। यंति। व्रतऽपां। अदाभ्य॥ ३१॥ त्वं। अग्ने। प्रथमं। आयुं। आय
वे। देवाः। अकृण्वन्। नहुषस्य। विश्पतिं। इळां। अकृण्वन्। मनुषस्य। शासनीं। पितुः। यत्।
पुत्रः। ममकस्य। जायते। ०। त्वं। नः। अग्ने। तव। देव। पायुऽभिः। मघोनः। रक्ष। तन्वः। च। वंद्य। त्रा २९

© Dharmartha Trust J&K. Digitized by eGangotri

ता। तोकस्य। तनये। गवां। असि। अनिऽमेषं। रक्षमाणः। तव। व्रते॥ त्वं। अग्ने। यज्यवे। पायुः।
अंतरः। अनिषंगाय। चतुःऽअक्षः। इध्यसे। यः। रातऽहव्यः। अवृकाय। धायसे। कीरेः। चि
त्। मंत्रं। मनसा। वनोषि। तं॥ त्वं। अग्ने। उरुऽशंसाय। वाघते। स्पार्हं। यत्। रेक्णः। परमं। व
नोषि। तत्। आध्रस्य। चित्। प्रऽमतिः। उच्यसे। पिता। प्र। पाकं। शास्सि। प्र। दिशः। विदुःऽतरः।
त्वं। अग्ने। प्रयतऽदक्षिणं। नरं। वर्मऽइव। स्यूतं। परि। पासि। विश्वतः। स्वादुऽक्षद्मा। यः। वसतौ।
स्योनऽकृत्। जीवऽयाजं। यजते। सः। उपऽमा। दिवः॥ १५॥ इमां। अग्ने। शरणिं। मीमृषः। नः।
इमं। अध्वानं। यं। अगाम। दूरात्। आपिः। पिता। प्रऽमतिः। सोम्यानां। भृमिः। असि। ऋषिऽकृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ त्।मर्त्यानां॥मनुष्वत्।अग्ने।अंगिरस्वत्।अंगिरः।ययातिऽवत्।सदने।पूर्वऽवत्।शुचे।अच्छ।
३० याहि।आ।वह।दैव्यं।जनं।आ।सादय।बर्हिषि।यक्षि।च।प्रियं॥एतेन।अग्ने।ब्रह्मणा।ववृध
स्व।शक्ती।वा।यत्।ते।चकृम।विदा।वा।उत।प्र।नेषि।अभि।वस्यः।अस्मान्।सं।नः।सृज।सु
30 ऽमत्या।वाजऽवत्या॥३५॥इंद्रस्य।नु।वीर्याणि।प्र।वोचं।यानि।चकार।प्रथमानि।वज्री।अ
हन्।अहिं।अनु।अपः।ततर्द।प्र।वक्षणाः।अभिनत्।पर्वतानां॥अहन्।अहिं।पर्वते।शिश्रिया
णं।त्वष्टा।अस्मै।वज्रं।स्वर्यं।ततक्ष।वाश्राःऽइव।धेनवः।स्यंदमानाः।अंजः।समुद्रं।अव।ज
ग्मुः।आपः।वृषऽयमाणः।अवृणीत।सोमं।त्रिऽकद्रुकेषु।अपिबत्।सुतस्य।आ।सायकं। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

मघऽवा। अदत्त। वज्रं। अहन्। एनं। प्रथमऽजां। अहीनां॥ यत्। इंद्र। अहन्। प्रथमऽजां। अहीनां।
आत्। मायिनां। अमिनाः। प्र। उत। मायाः। आत्। सूर्यं। जनयन्। द्यां। उषसं। तादीत्ना। शत्रुं। न।
किल। विवित्से॥ अहन्। वृत्रं। वृत्रऽतरं। विऽअंसं। इंद्रः। वज्रेण। महता। वधेन। स्कंधांसिऽइव।
कुलिशेन। विऽवृक्णा। अहिः। शयते। उपऽपृक्। पृथिव्याः॥३॥ अयोद्धाऽइव। दुःऽमदः। आ।
हि। जुह्वे। महाऽवीरं। तुविऽबाधं। ऋजीषं। न। अतारीत्। अस्य। संऽऋतिं। वधानां। सं। रुजा
नाः। पिपिषे। इंद्रऽशत्रुः॥ अपात्। अहस्तः। अपृतन्यत्। इंद्रं। आ। अस्य। वज्रं। अधि। सानौ।
जघान। वृष्णः। वध्रिः। प्रतिऽमानं। बुभूषन्। पुरुऽत्रा। वृत्रः। अशयत्। विऽअस्तः॥ नदं। न।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ भिन्नं। अमुया। शयानं। मनः। रुहाणाः। अति। यंति। आपः। याः। चित्। वृत्रः। महिना। परिऽअति
३१ ष्ठत्। तासां। अहिः। पत्सुतःऽशीः। बभूव। नीचाऽवयाः। अभवत्। वृत्रऽपुत्रा। इंद्रः। अस्याः। अ
व। वधः। जभार। उत्ऽतरा। सूः। अधरः। पुत्रः। आसीत्। दानुः। शये। सहऽवत्सा। न। धेनुः। अ
तिष्ठंतीनां। अनिऽवेशनानां। काष्ठानां। मध्ये। निऽहितं। शरीरं। वृत्रस्य। निण्यं। वि। चरंति। आ
पः। दीर्घं। तमः। आ। अशयत्। इंद्रऽशत्रुः। दासऽपत्नीः। अहिऽगोपाः। अतिष्ठन्। निऽरुद्धाः।
आपः। पणिनाऽइव। गावः। अपां। बिलं। अपिऽहितं। यत्। आसीत्। वृत्रं। जघन्वान्। अप। त
त्। ववार। अश्व्यः। वारः। अभवः। तत्। इंद्र। सृके। यत्। त्वा। प्रतिऽअहन्। देवः। एकः। अजयः। ३१

31

© Dharmartha Trust J&K. Digitized by eGangotri

गाः। अजयः। शूर। सोमं। अव। असृजः। सर्तवे। सप्त। सिंधून्॥ न। अस्मै। विऽद्युत्। न। तन्यतुः।
सिषेध। न। यां। मिहं। अकिरत्। ह्रादुनिं। च। इंद्रः। च। यत्। युयुधाते इति। अहिः। च। उत। अप
रीभ्यः। मघऽवा। वि। जिग्ये॥ अहेः। यातारं। कं। अपश्यः। इंद्र। हृदि। यत्। ते। जघ्नुषः। भीः। अग
छत्। नव। च। यत्। नवतिं। च। स्रवंतीः। श्येनः। न। भीतः। अतरः। रजांसि॥ इंद्रः। यातः। अवऽसि
तस्य। राजा। शमस्य। च। शृंगिणः। वज्रऽबाहुः। सः। इत्। ऊं इति। राजा। क्षयति। चर्षणीनां। अ
रान्। न। नेमिः। परि। ता। बभूव॥ १५॥ इति प्रथमाष्टके द्वितीयोऽध्यायः॥ ॐ॥ एतत्त्रिश्चिद्वा
दशाश्विनं नवम्यं से त्रिष्टुभौ कृया म्येकादशा सावित्रं नवमी जगत्याद्याचसास्तिं गोक्तै देवतपा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ दांम्रवो विंशतिः कण्वो घोर आग्नेयं प्रागाथं मूर्ध्व ऋग्युय्यो चौक्रीकं पंचो नामास्तं हिगा
३२ यत्रं तु कद्धुप्र यद्दशा प्रागाथं नृत्रिष्टा शेषो ब्राह्मणस्पत्यं यं रक्षंति नव वरुण मित्रार्यम्णां म
ध्ये तृच आदित्येभ्यो गायत्रं हि संपूषंद्दशपौर्ष्ण्यं कद्रुद्राय नव रौद्रं तृतीया मैत्रावरुणी चां
स्तृचः सौम्यां स्यानुष्टुब ग्नेष कृ नाप्रस्कण्वः काण्व आग्नेयं तु प्रागाथं मा यो द्वचो भ्युष
सांचं त्वमग्ने दशानुष्टुभ मर्धर्चौ स्यादेवं ऽषो पंचो नाश्विनं तु गायत्रं ॥३॥ हरिः ॐ ॥ आ इता ।
अ यामा । उपा । गव्यंतः । इंद्रा । अस्माकं । सुप्रऽमतिं । वरुधातिं । अनारणः । कुवित्स्व । आत्वा । अस्या ।
रायः । गवां । केतं । परं । आऽवर्जनं । नः ॥ उपाऽइत्वा । अंहः । धनऽदां । अप्रतिऽइतं । जुष्टां । नाऽइयेनः । ३२

© Dharmartha Trust J&K. Digitized by eGangotri

वसतिं। पतामि। इंद्रं। नमस्यन्। उपऽमेभिः। अर्कैः। यः। स्तोतृऽभ्यः। हव्यः। अस्ति। यामन्॥ नि।
सर्वऽसेनः। इषुऽधीन्। असक्त। सं। अर्यः। गाः। अजति। यस्य। वष्टि। चोष्कूयमाणः। इंद्र। भूरि।
वामं। मा। पणिः। भूः। अस्मत्। अधि। प्रऽवृद्ध॥ वधीः। हि। दस्युं। धनिनं। घनेन। एकः। चरन्।
उपऽशाकेभिः। इंद्र। धनोः। अधि। विषुणक्। ते। वि। आयन्। अयज्वानः। सनकाः। प्रऽइतिं। ई
युः। परा। चित्। शीर्षा। ववृजुः। ते। इंद्र। अयज्वानः। यज्वऽभिः। स्पर्धमानाः। प्र। यत्। दिवः। ह
रिऽवः। स्थातः। उग्र। निः। अव्रतान्। अधमः। रोदस्योः॥ १॥ अयुयुत्सन्। अनवद्यस्य। सेनां। अ
यातयंत। क्षितयः। नवऽग्वाः। वृषऽयुधः। न। वध्रयः। निःऽअष्टाः। प्रवत्ऽभिः। इंद्रात्। चितयंत

प.प्र. नेः।आयन्।।त्वं।एतान्।रुदतः।जक्षतः।च।अयोधयः।रजसः।इन्द्र।पारे।अव।अदहः।दिवः।
३३ आ।दस्युं।उच्चा।प्र।असुन्वतः।स्तुवतः।शंसं।आवः।।चक्राणासः।परिऽनहं।पृथिव्याः।हिरण्ये
ना न।मणिना।शुंभमानाः।न।हिन्वानासः।तितिरुः।ते।इन्द्रं।परि।स्पशः।अदधात्।सूर्येण।।परि।
33 यत्।इन्द्र।रोदसी इति।उभे इति।अबुभोजीः।महिना।विश्वतः।सीं।अमन्यमानान्।अभि।
मन्यमानैः।निः।ब्रह्मऽभिः।अधमः।दस्युं।इन्द्र।।न।ये।दिवः।पृथिव्याः।अंतं।आपुः।न।माया
भिः।धनऽदां।परि।अभवन्।युजं।वज्रं।वृषभः।चक्रे।इन्द्रः।निः।ज्योतिषा।तमसः।गाः।अ
धुक्षत्।।२।।अनु।स्वधां।अक्षरन्।आपः।अस्य।अवर्धत।मध्ये।आ।नाव्यानां।सध्रीचीनेन। ३३

मनसा। तं। इंद्रः। ओजिष्ठेन। हन्मना। अहन्। अभि। द्यून्॥ न। अविध्यत। इलीबिशस्य। दृळ्हा।
वि। शृंगिणं। अभिनत्। शुष्णं। इंद्रः। यावत्। तरः। मघऽवन्। यावत्। ओजः। वज्रेण। शत्रुं। अव
धीः। पृतन्युं॥ अभि। सिध्मः। अजिगात्। अस्य। शत्रून्। वि। तिग्मेन। वृषभेण। पुरः। अभेत्।
सं। वज्रेण। असृजत्। वृत्रं। इंद्रः। प्र। स्वां। मतिं। अतिरत्। शाशदानः॥ आवः। कुत्सं। इंद्र। यस्मि
न्। चाकन्। प्र। आवः। युध्यंतं। वृषभं। दशऽद्युं। शफऽच्युतः। रेणुः। नक्षत। द्यां। उत्। श्वैत्रेयः। नृऽ
सह्याय। तस्थौ॥ आवः। शमं। वृषभं। तुग्र्यासु। क्षेत्रऽजेषे। मघऽवन्। श्वित्र्यं। गां। ज्योक्। चि
त्। अत्र। तस्थिऽवांसः। अक्रन्। शत्रुऽयतां। अधरा। वेदना। अकः॥ ३॥ त्रिः। चित्। नः।

© Dharmartha Trust J&K. Digitized by eGangotri

अध। भवतं। नवेदसा। विऽभुः। वां। यामः। उत। रातिः। अश्विना। युवोः। हि। यंत्रा। हिम्याऽइव। वा
ससः। अभि। आऽयंसेन्या। भवतं। मनीषिऽभिः। त्रयः। पवयः। मधुऽवाहने। रथे। सोमस्य। वेनां। मे
अनु। विश्वे। इत्। विदुः। त्रयः। स्कंभासः। स्कभितासः। आऽरभे। त्रिः। नक्तं। याथः। त्रिः। ऊं इति।
अश्विना। दिवा।। समाने। अहन्। त्रिः। अवद्यऽगोहना। त्रिः। अद्य। यज्ञं। मधुना। मिमिक्षतं।
त्रिः। वाजऽवतीः। इषः। अश्विना। युवं। दोषाः। अस्मभ्यं। उषसः। च। पिन्वतं।। त्रिः। वर्तिः। यातं। त्रिः।
अनुऽव्रते। जने। त्रिः। सुप्रऽअव्ये। त्रेधाऽइव। शिक्षतं। त्रिः। नांद्यं। वहतं। अश्विना। युवं। त्रिः। पृक्षः।
अस्मे इति। अक्षराऽइव। पिन्वतं।। त्रिः। नः। रयिं। वहतं। अश्विना। युवं। त्रिः। देवऽताता। त्रिः। उत। ३५

© Dharmartha Trust J&K. Digitized by eGangotri

अवतं । धियः । त्रिः । सौभगऽत्वं । त्रिः । उत । श्रवांसि । नः । त्रिऽस्थं । वां । सूरे । दुहिता । आ । रुहत् । रथं ॥
त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवानि । त्रिः । ऊं इति । दत्तं । अत्ऽभ्यः । ओमानं । शं
ऽयोः । ममकाय । सूनवे । त्रिऽधातु । शर्म । वहतं । शुभः । पती इति ॥६॥ त्रिर्नो अश्विना । यजता ।
दिवेऽदिवे । परि । त्रिऽधातु । पृथिवीं । अशायतं । तिस्रः । नासत्या । रथ्या । पराऽवतः । आत्माऽइव ।
वातः । स्वसराणि । गच्छतं ॥ त्रिः । अश्विना । सिंधुऽभिः । सप्तमातृऽभिः । त्रयः । आऽहावाः । त्रेधा ।
हविः । कृतं । तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकं । रक्षेथे इति । द्युऽभिः । अक्तुऽभिः । हितं ॥ क्व ।
त्री । चक्रा । त्रिऽवृतः । रथस्य । क्व । त्रयः । वंधुरः । ये । सऽनीळाः । कदा । योगः । वाजिनः । रासभस्य ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ग्र॰ येना। युञ्जाना। सत्या। उप। याथः॥ आ। नासत्या। गच्छतं। हूयते। हविः। मध्वः। पिबतं। मधुऽपेभिः। आस
३५ ऽभिः। युवोः। हि। पूर्वं। सविता। उषसः। रथं। ऋताय। चित्रं। घृतऽवंतं। इष्यति॥ आ। नासत्या। त्रिऽभिः।
35 एकादशैः। इह। देवेभिः। यातं। मधुऽपेयं। अश्विना। प्र। आयुः। तारिष्टं। निः। रपांसि। मृक्षतं। सेध
तं। द्वेषः। भवतं। सचाऽभुवा॥ आ। नः। अश्विना। त्रिऽवृता। रथेन। अर्वांचं। रयिं। वहतं। सुऽवीरं।
शृण्वंता। वां। अवसे। जोहवीमि। वृधे। च। नः। भवतं। वाजऽसातौ॥ ५॥ ह्वयामि। अग्निं। प्रथमं। स्व
रु स्तये। ह्वयामि। मित्रावरुणौ। इह। अवसे। ह्वयामि। रात्रीं। जगतः। निऽवेशनीं। ह्वयामि। देवं। स
वितारं। ऊतये॥ आ। कृष्णेन। रजसा। वर्तमानः। निऽवेशयन्। अमृतं। मर्त्यं। च। हिरण्ययेन। सवि ३५

© Dharmartha Trust J&K. Digitized by eGangotri

ना। रथेन। आ। देवः। याति। भुवनानि। पश्यन्॥ याति। देवः। प्रऽवता। याति। उत्ऽवता। याति। शु
भ्राभ्यां। यजतः। हरिऽभ्यां। आ। देवः। याति। सविता। पराऽवतः। अप। विश्वा। दुःऽइता। बाधमा
नः॥ अभिऽवृतं। कृशनैः। विश्वऽरूपं। हिरण्यऽशम्यं। यजतः। बृहन्तं। आ। अस्थात्। रथं। सविता।
चित्रऽभानुः। कृष्णा। रजांसि। तविषीं। दधानः॥ वि। जनान्। श्यावाः। शितिऽपादः। अख्यन्। र
थं। हिरण्यऽप्रउगं। वहन्तः। शश्वत्। विशः। सवितुः। दैव्यस्य। उपऽस्थे। विश्वा। भुवनानि। तस्थुः॥
तिस्रः। द्यावः। सवितुः। द्वौ। उपऽस्था। एका। यमस्य। भुवने। विराषाट्। आणिं। न। रथ्यं। अमृता।
अधि। तस्थुः। इह। ब्रवीतु। यः। ऊं इति। तत्। चिकेतत्॥ ६॥ वि। सुऽपर्णः। अंतरिक्षाणि। अख्यत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ गभीरऽवेपाः। असुरः। सुऽनीथः। क्व। इदानीं। सूर्यः। कः। चिकेत। कतमां। द्यां। रश्मिः। अस्य। आ।
३६ ततान। अष्टौ। वि। अख्यत्। ककुभः। पृथिव्याः। त्री। धन्व। योजना। सप्त। सिंधून्। हिरण्यऽअ
36 क्षः। सविता। देवः। आ। अगात्। दधत्। रत्ना। दाशुषे। वार्याणि॥ हिरण्यऽपाणिः। सविता। विऽ
चर्षणिः। उभे इति। द्यावापृथिवी इति। अंतः। ईयते। अप। अमीवां। बाधते। वेति। सूर्यं। अभि।
कृष्णेन। रजसा। द्यां। ऋणोति॥ हिरण्यऽहस्तः। असुरः। सुऽनीथः। सुऽमृळीकः। स्वऽवान्। यातु।
अर्वाङ्। अपऽसेधन्। रक्षसः। यातुऽधानान्। अस्थात्। देवः। प्रतिऽदोषं। गृणानः॥ ये। ते। पंथाः।
सवितरिति। पूर्व्यासः। अरेणवः। सुऽकृताः। अंतरिक्षे। तेभिः। नः। अद्य। पथिऽभिः। सुगेभिः। ३५

© Dharmartha Trust J&K. Digitized by eGangotri

रक्ष । च । नः । अधि । च । ब्रूहि । देव । ७ । प्र । वः । यह्वं । पुरूणां । विशां । देवऽयतीनां । अग्निं । सुऽउक्तेभिः ।
वचःऽभिः । ईमहे । यं । सीं । इत् । अन्ये । ईळते । जनाः । सः । अग्निं । दधिरे । सहःऽवृधं । हविष्मंतः । विधे
म । ते । सः । त्वं । नः । अद्य । सुऽमनाः । इह । अविता । भव । वाजेषु । संत्य । प्र । त्वा । दूतं । वृणीमहे । हो
तारं । विश्वऽवेदसं । महः । ते । सतः । वि । चरंति । अर्चयः । दिवि । स्पृशंति । भानवः । देवासः । त्वा ।
वरुणः । मित्रः । अर्यमा । सं । दूतं । प्रत्नं । इंधते । विश्वं । सः । अग्ने । जयति । त्वया । धनं । यः । ते । द
दाश । मर्तः । मंद्रः । होता । गृहऽपतिः । अग्ने । दूतः । विशां । असि । त्वे इति । विश्वा । संऽगतानि ।
व्रता । ध्रुवा । यानि । देवाः । अकृण्वत । ८ । त्वे इति । इत् । अग्ने । सुऽभगे । यविष्ठ्य । विश्वं । आ । हू

© Dharmartha Trust J&K. Digitized by eGangotri

क.म. यते। हविः। ० सत्वंनोअद्यसुमना। उत। अपरं। यक्षि। देवान्। सुऽवीर्या॥ तं। घ। ईं। इत्था। नमस्विनः।
३८ उप। स्वऽराजं। आसते। होत्राभिः। अग्निं। मनुषः। सं। इंधते। तितिर्वांसः। अति। स्रिधः॥ घ्नंतः।
वृत्रं। अतरन्। रोदसी इति। अपः। उरु। क्षयाय। चक्रिरे। भुवत्। कण्वे। वृषा। द्युम्नी। आऽहुतः। क्रं-
37 दत्। अश्वः। गोऽइष्टिषु॥ सं। सीदस्व। महान्। असि। शोचस्व। देवऽवीतमः। वि। धूमं। अग्ने। अ-
रुषं। मियेध्य। सृज। प्रऽशस्त। दर्शतं॥ यं। त्वा। देवासः। मनवे। दधुः। इह। यजिष्ठं। हव्यऽवाहन।
यं। कण्वः। मेध्यऽअतिथिः। धनऽस्पृतं। यं। वृषा। यं। उपऽस्तुतः॥ १॥ यं। अग्निं। मेध्यऽअतिथिः।
कण्वः। ईधे। ऋतात्। अधि। तस्य। प्र। इषः। दीदियुः। तं। इमाः। ऋचः। तं। अग्निं। वर्धयामसि॥ ३८

© Dharmartha Trust J&K. Digitized by eGangotri

रायः। पूर्धि। स्वधाऽवः। अस्ति। हि। ते। अग्ने। देवेषु। आप्यं। त्वं। वाजस्य। श्रुत्यस्य। राजसि। सः। नः। मृ

ळ। ऊर्ध्वः। ऊं इति। सु। नः। ऊतये। तिष्ठ। देवः। न। सविता। ऊर्ध्वः। वाजस्य। सनिता।

यत्। अंजिऽभिः। वाघत्ऽभिः। विऽह्वयामहे। ऊर्ध्वः। नः। पाहि। अंहसः। नि। केतुना। विश्वं। सं। अ

त्रिणं। दह। कृधि। नः। ऊर्ध्वान्। चरथाय। जीवसे। विदाः। देवेषु। नः। दुवः॥ पाहि। नः। अग्ने। रक्षसः।

पाहि। धूर्तेः। अराव्णः। पाहि। रिषतः। उत। वा। जिघांसतः। बृहद्भानो इति बृहत्ऽभानो। यविष्ठ्य

॥१०॥ घनाऽइव। विष्वक्। वि। जहि। अराव्णः। तपुःऽजंभ। यः। अस्मऽध्रुक्। यः। मर्त्यः। शिशीते।

अति। अक्तुऽभिः। मा। नः। सः। रिपुः। ईशत॥ अग्निः। वव्ने। सुऽवीर्यं। अग्निः। कण्वाय। सौभगं।

© Dharmartha Trust J&K. Digitized by eGangotri

हे

प.प्र अग्निः । प्र । आवत् । मित्रा । उत । मेध्यऽआतिथिं । अग्निः । साता । उपऽस्तुतं ॥ अग्निना । तुर्वशं । यदुं । प
३८ राऽवतः । उग्रऽदेवं । हवामहे ॥ अग्निः । नयत् । नवऽवास्त्वं । बृहत्ऽरथं । तुर्वीतिं । दस्यवे । सहः ॥ निं । त्वां ।
अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते ॥ दीदेथ । कण्वे । ऋतऽजातः । उक्षितः । यं । नमस्यंति । कृ
ष्टयः ॥ त्वेषासः । अग्नेः । अमऽवंतः । अर्चयः । भीमासः । न । प्रतिऽइतये ॥ रक्षस्विनः । सदं । इत् । या
तुऽमावतः ॥ विश्वं सं अत्रिणं दह ॥ ३ ॥ क्रीळं । वः । शर्धः । मारुतं । अनर्वाणं । रथेऽशुभं । कण्वाः ।
अभि । प्र । गायत ॥ ये । पृषतीभिः । ऋष्टिऽभिः । साकं । वाशीभिः । अंजिऽभिः । अजायंत । स्वऽभा
नवः ॥ इहऽइव । शृण्वे । एषां । कशाः । हस्तेषु । यत् । वदान् ॥ नि । यामन् । चित्रं । ऋंजते ॥ प्र । वः । शर्द्धं ३८

38

© Dharmartha Trust J&K. Digitized by eGangotri

या।द्यव्ये।लेपः।द्युम्नाय।भूष्मिणो।देवत्तो।ब्रसी।गा।यत्ना।प्रा।शुं।सा।गोषु।अघ्न्यौ।क्री।कं।यत्ना।ऊर्ध्वः।मा

रुतो।अंमे।रसस्या।वृरुधे॥३२॥कः।वः।वर्षिष्ठः।आ।नुरः।दिवः।चा।ग्मः।चा।पूतयः।यत्ना।सीं।अंतो।

ना।धूनुथ॥निवः।यामा।या।मानुषः।दध्रो।उग्रा।या।मन्यवे।जिहीत।पर्वतः।गिरिः।येषां।अज्मेषु।

पृथिवी।जुजुर्वान्।इवा।विश्पतिः।भिया।या।मेषु।रेजते।स्थिरं।हि।जानं।एषां।वयः।मातुः।निः

एतवे।यत्ना।सीं।अनु।द्विता।शवः।उत्ता।क्रंदतिं।सो।सूनवः।गिरः।काष्ठाः।अज्मेषु।अत्नता।वा।श्राः

अभिः।ज्ञु।यातवे॥३३॥सो।चिन्ना।घा।दीर्घं।पृथुं।मिहः।नपातं।अमृध्रं।प्र।च्यवयंति।यामभिः।म

रुतः।यत्ना।हा।वृञ्ज्वलो।जनो।ना।अचु च्यवीतन।गिरीन्।अचु च्यवीतन।यत्ना।हा।यांति।मरुतः।सो।

© Dharmartha Trust J&K. Digitized by eGangotri

ऋग्॰ हा। बृहते। अध्वरः। आ। शृणोति। कः। चित्। एषां॥ प्र। यात। शीभं। आशुऽभिः। संति। कण्वेषु। वः। दुवः। त

३९ त्रोऽइति। सु। मादयाध्वै॥ अस्ति। हि। स्म। मदाय। वः। स्मसि। वयं। एषां। विश्वं। चित्। आयुः। जीवसे॥

३४। कत्। ह। नूनं। कधऽप्रियः। पिता। पुत्रं। न। हस्तयोः। दधिध्वे। वृक्तऽबर्हिषः॥ क्व। नूनं। कत्। वः। अ

र्थं। गंत। दिवः। न। पृथिव्याः॥ क्व। वः। गावः। न। रण्यंति॥ क्व। वः। सुम्ना। नव्यांसि। मरुतः। क्व। सुविता। क्वो

इति। विश्वानि। सौभगा॥ यत्। यूयं। पृश्निऽमातरः। मर्तासः। स्यातन। स्तोता। वः। अमृतः। स्यात॥

मा। वः। मृगः। न। यवसे। जरिता। भूत्। अजोष्यः। पथा। यमस्य। गात्। उप॥ ३५। मो इति। सु। नः। प

रा। परा। निःऽऋतिः। दुःऽहना। वधीत्। पदीष्ट। तृष्णया। सह॥ सत्यं। त्वेषाः। अमऽवंतः। धन्वन्। चित्। ३९

© Dharmartha Trust J&K. Digitized by eGangotri

आ । रुद्रियासः । मिहं । कृण्वंति । अवातां ॥ वाश्राःऽइव । विऽद्युत् । मिमाति । वत्सं । न । माता । सिसक्ति ।
यत् । एषां । वृष्टिः । असर्जि ॥ दिवा । चित् । तमः । कृण्वंति । पर्जन्येन । उदऽवाहेन । यत् । पृथिवीं । विऽ
उंदंति ॥ अध । स्वनात् । मरुतां । विश्वं । आ । सद्म । पार्थिवं । अरेजंत । प्र । मानुषाः ॥ १० ॥ मरुतः । वी
ळुपाणिऽभिः । चित्राः । रोधस्वतीः । अनु । यात । ईं । अखिद्रयामऽभिः ॥ स्थिराः । वः । संतु । नेमयः ।
रथाः । अश्वासः । एषां । सुऽसंस्कृताः । अभीशवः ॥ अच्छ । वद । तना । गिरा । जरायै । ब्रह्मणः । प
तिं । अग्निं । मित्रं । न । दर्शतं ॥ मिमीहि । श्लोकं । आस्ये । पर्जन्यःऽइव । ततनः । गाय । गायत्रं । उक्थ्यं ॥
वंदस्व । मारुतं । गणं । त्वेषं । पनस्युं । अर्किणं । अस्मे इति । वृद्धाः । असन् । इह ॥ १५ ॥ प्र । यत् । इत्था ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ परा॒ऽवतः।शो॒चिः।न।मानं॑।अस्य॑थ।कस्य॑।क्रत्वा॑।म॒रु॒तः॒।कस्य॑।वर्प॑सा।कं।या॒थ॒।कं।ह॒।धू॒त॒यः॒॥स्थि॒रा।

५० वः॒।स॒न्तु॒।आयु॑धा।प॒रा॒ऽनुदे॑।वी॒ळु।उ॒त।प्र॒ति॒ऽस्कभे॑।यु॒ष्माकं॑।अ॒स्तु॒।तवि॑षी।पनी॑यसी।मा।मर्त्य॑स्य।

40 मा॒यिनः॑॥परा॑।ह॒।यत्।स्थि॒रं।ह॒थ।नरः॑।व॒र्तय॑थ।गु॒रु।वि।या॒थ॒न॒।व॒निनः॑।पृ॒थि॒व्याः।वि।आशाः॑।

पर्व॑तानां॥न॒हि।वः॒।शत्रुः॑।वि॒वि॒दे।अधि॑।द्यवि॑।न।भूम्यां॑।रि॒शा॒द॒सः॒॥१०॥ युष्माकमस्तुतविषी।तना॑।यु॒

जा।रुद्रा॑सः।नु॒।चि॒त्।आ॒ऽधृषे॑॥प्र।वे॒प॒यं॒ति॒।पर्व॑तान्।वि।वि॒विं॒च॒ति॒।व॒न॒स्प॒न्।प्रो इति॑।आ॒र॒त॒।म॒रु॒ तीं

तः॒।दु॒र्मदाः॑ऽइव।देवाः॑।सः॒।सर्व॑या।वि॒शा॥११॥उपो॒ इति॑।रथे॑षु।पृष॑तीः।अ॒यु॒ग्ध्वं॒।प्रष्टिः॑।व॒ह॒ति॒।रो

हि॑तः।आ।वः॒।यामा॑य।पृ॒थि॒वी।चि॒त्।अ॒श्रो॒त्।अबी॑भयंत।मानु॑षाः॥आ।वः॒।म॒क्षु।तना॑य।कं। ५०

© Dharmartha Trust J&K. Digitized by eGangotri

रुद्राः । अवः । वृणीमहे । गंत । नूनं । नः । अवसा । यथा । पुरा । इत्था । कण्वाय । बिभ्युषे । युष्माऽइषितः ।
मरुतः । मर्त्यऽइषितः । आ । यः । नः । अभ्वः । ईषते । वि । तं । युयोत । शवसा । वि । ओजसा । वि । युष्माका
भिः । ऊतिऽभिः ॥ असामि । हि । प्रऽयज्यवः । कण्वं । दद । प्रऽचेतसः । असामिऽभिः । मरुतः । आ । नः ।
ऊतिऽभिः । गंत । वृष्टिं । न । विऽद्युतः ॥ असामि । ओजः । बिभृथ । सुऽदानवः । असामि । धूतयः । शवः ।
ऋषिऽद्विषे । मरुतः । परिऽमन्यवे । इषुं । न । सृजत । द्विषं ॥ १ ॥ उत् । तिष्ठ । ब्रह्मणः । पते । देवऽयंतः ।
त्वा । ईमहे । उप । प्र । यंतु । मरुतः । सुऽदानवः । इंद्र । प्राशूः । भव । सचा ॥ त्वां । इत् । हि । सहसः । पुत्र । म
र्त्यः । उपऽब्रूते । धने । हिते । सुऽवीर्यं । मरुतः । आ । सुऽअश्व्यं । दधीत । यः । वः । आऽचके ॥ प्र । एतु । ब्रह्म

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ णः। पतिः। प्र। देवी। एतु। सूनृता। अच्छ। वीरं। नर्यं। पंक्तिऽराधसं। देवाः। यज्ञं। नयंतु। नः॥ यः। वाघते।
४१ ददाति। सूनरं। वसु। सः। धत्ते। अक्षिति। श्रवः॥ तस्मै। इळां। सुऽवीरां। आ। यजामहे। सुऽप्रतूर्तिं।
अनेहसं॥ प्र। नूनं। ब्रह्मणः। पतिः। मंत्रं। वदति। उक्थ्यं। यस्मिन्। इंद्रः। वरुणः। मित्रः। अर्यमा। द
41 वाः। ओकांसि। चक्रिरे॥ तं। इत्। वोचेम। विदथेषु। शंऽभुवं। मंत्रं। देवाः। अनेहसं। इमां। च। वा
चं। प्रतिऽहर्यथ। नरः। विश्वा। इत्। वामा। वः। अश्नवत्॥ कः। देवऽयंतं। अश्नवत्। जनं। कः। वृक्तऽ
बर्हिषं। प्रऽप्र। दाश्वान्। पस्त्याभिः। अस्थित। अंतःऽवावत्। क्षयं। दधे॥ उप। क्षत्रं। पृंचीत। हंति।
राजऽभिः। भये। चित्। सुऽक्षितिं। दधे॥ न। अस्य। वर्ता। न। तरुता। महाऽधने। न। अर्भे। अस्ति। व ४१

© Dharmartha Trust J&K. Digitized by eGangotri

ज्रिणः ॥ ३ ॥ यं । रक्षन्ति । प्रऽचेतसः । वरुणो । मित्रो अर्यमा । नु । चित् । सः । दभ्यते । जनः ॥ यं । बाहुताऽ
इव । पिप्रति । पान्ति । मर्त्यं । रिषः । अरिष्टः । सर्वः । एधते ॥ वि । दुःऽगा । वि । द्विषः । पुरः । घ्नन्ति । राजानः ।
एषां ॥ नयन्ति । दुःऽइता । तिरः ॥ सुऽगः । पन्थाः । अनृक्षरः । आदित्यासः । ऋतं । यते । न । अत्र । अवऽखा
दः । अस्ति । वः ॥ यं । यज्ञं । नयथ । नरः । आदित्याः । ऋजुना । पथा । प्र । वः । सः । धीतये । नशत् ॥ ४ ॥
सः । रत्नं । मर्त्यः । वसु । विश्वं । तोकं । उत । त्मना । अच्छ । गच्छति । अस्तृतः ॥ कथा । राधाम । सखायः ।
स्तोमं । मित्रस्य । अर्यम्णः । महि । प्सरः । वरुणस्य ॥ मा । वः । घ्नन्तं । मा । शपन्तं । प्रति । वोचे । देवऽयं
तं । सुम्नैः । इत् । वः । आ । विवासे ॥ चतुरः । चित् । ददमानात् । बिभीयात् । आ । निऽधातोः । न । दुःऽउ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ग्र॰ क्रायः। सुऽहवेन।। २४।। सं। पूषन्। अध्वनः। तिर। वि। अंहः। विऽमुचः। नपात्। सक्ष्व। देव। प्र। नः। पुरः।।
५२ यः। नः। पूषन्। अघः। वृकः। दुःऽशेवः। आऽदिदेशति। अप। स्म। तं। पथः। जहि।। अप। त्यं। परिऽ
पंथिनं। मुषीवाणं। हुरःऽचितं। दूरं। अधि। स्रुतेः। अज।। त्वं। तस्य। द्वयाविनः। अघऽशंसस्य। क
42 स्य। चित्। पदा। अभि। तिष्ठ। तपुषिं।। आ। तत्। ते। दस्र। मंतुऽमः। पूषन्। अवः। वृणीमहे। येन। पि
तॄन्। अचोदयः।। २५।। अध। नः। विश्वऽसौभग। हिरण्यवाशीमत्ऽतम। धनानि। सुऽसना।
कृधि।। अति। नः। सश्चतः। नय। सुऽगा। नः। सुऽपथा। कृणु। पूषन्। इह। क्रतुं। विदः।। अभि। सुऽ
यवसं। नय। न। नवऽज्वारः। अध्वने।। ० पूषं इह क्रतुं विदः। शग्धि। पूर्धि। प्र। यंसि। च। शिशीहि। ५२

© Dharmartha Trust J&K. Digitized by eGangotri

प्रासि। उदरं। न। पूषणं। मेथामसि। सुऽउक्तैः। अभि। गृणीमसि। वसूनि। दस्मं। ईमहे॥ २५॥ क
त्। रुद्राय। प्रऽचेतसे। मीळ्हुःऽतमाय। तव्यसे। वोचेम। शंऽतमं। हृदे॥ यथा। नः। अदितिः। क
रत्। पश्वे। नृऽभ्यः। यथा। गवे। यथा। तोकाय। रुद्रियं॥ यथा। नः। मित्रः। वरुणः। यथा। रुद्रः। चि
केतति। यथा। विश्वे। सऽजोषसः॥ गाथऽपतिं। मेधऽपतिं। रुद्रं। जलाषऽभेषजं। तत्। शंऽयोः। सु
म्नं। ईमहे॥ यः। शुक्रःऽइव। सूर्यः। हिरण्यंऽइव। रोचते। श्रेष्ठः। देवानां। वसुः॥ २६॥ शं। नः। कर
ति। अर्वते। सुऽगं। मेषाय। मेष्यै। नृऽभ्यः। नारिऽभ्यः। गवे॥ अस्मेइति। सोम। श्रियं। अधि। नि।
धेहि। शतस्य। नृणां। महि। श्रवः। तुविऽनृम्णं॥ मा। नः। सोमऽपरिबाधः। मा। अरातयः। जु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ कृत्वा। आ। नः। इंद्रो इति। वाजं। भज।। याः। ते। म्रऽजाः। अमृतस्य। परस्मिन्। धामन्। ऋतस्य। मू

५२ र्धा। नाभा। सोम। वेनः। आऽभूषंतीः। सोम। वेदः।। २०।। अग्ने। विवस्वत्। उषसः। चित्रं। राधः।

५३ अमर्त्य। आ। दाशुषे। जातऽवेदः। वह। त्वं। अद्य। देवान्। उषःऽबुधः।। जुष्टः। हि। दूतः। असि। हव्य

ऽवाहनः। अग्ने। रथीः। अध्वराणां। सऽजूः। अश्विभ्यां। उषसा। सुऽवीर्यं। अस्मे इति। धेहि। श्रवः।

बृहत्।। अद्य। दूतं। वृणीमहे। वसुं। अग्निं। पुरुऽप्रियं। धूमऽकेतुं। भाःऽऋजीकं। विऽउष्टिषु। य

ज्ञानां। अध्वरऽश्रियं।। श्रेष्ठं। यविष्ठं। अतिथिं। सुऽआहुतं। जुष्टं। जनाय। दाशुषे। देवान्। अच्छ।

यातवे। जातऽवेदसं। अग्निं। ईळे। विऽउष्टिषु।। स्तविष्यामि। त्वां। अहं। विश्वस्य। अमृत। भो ५३

© Dharmartha Trust J&K. Digitized by eGangotri

जन। अग्ने। त्रातारं। अमृतं। मियेध्य। यजिष्ठं। हव्यऽवाहन॥ ५॥ सुऽशंसः। बोधि। गृणते। यविष्ठ्य।
मधुऽजिह्वः। सुऽआहुतः। प्रस्कण्वस्य। प्रऽतिरन्। आयुः। जीवसे। नमस्या। दैव्यं। जनं॥ होतारं। वि
श्वऽवेदसं। सं। हि। त्वा। विशः। इंधते। सः। आ। वह। पुरुऽहूत। प्रऽचेतसः। अग्ने। देवान्। इह। द्रवत्॥
सवितारं। उषसं। अश्विना। भगं। अग्निं। विऽउष्टिषु। क्षपः। कण्वासः। त्वा। सुतऽसोमासः। इंध
ते। हव्यऽवाहं। सुऽअध्वर॥ पतिः। हि। अध्वराणां। अग्ने। दूतः। विशां। असि। उषःऽबुधः। आ। वह।
सोमऽपीतये। देवान्। अद्य। स्वःऽदृशः॥ अग्ने। पूर्वाः। अनु। उषसः। विभावसो इति विभाऽवसो।
दीदेथ। विश्वऽदर्शतः। असि। ग्रामेषु। अविता। पुरःऽहितः। असि। यज्ञेषु। मानुषः॥ १०॥ नि। त्वा।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ यज्ञस्य।साधनं।अग्ने।होतारं।ऋत्विजं।मनुष्वत्।देव।धीमहि।प्रऽचेतसं।जीरं।दूतं।अमर्त्यं।।यत्।
५४ देवानां।मित्रऽमहः।पुरःऽहितः।अंतरः।यासि।दूत्यं।सिंधोःऽइव।प्रऽस्वनितासः।ऊर्मयः।अग्नेः।भ्रा
त जंते।अर्चयः।।श्रुधि।श्रुत्ऽकर्ण।वह्निऽभिः।देवैः।अग्ने।सयावऽभिः।आ।सीदंतु।बर्हिषि।मित्रः।अ
55 र्यमा।प्रातःऽयावानः।अध्वरं।।शृण्वंतु।स्तोमं।मरुतः।सुऽदानवः।अग्निऽजिह्वाः।ऋतऽवृधः।पि
बतु।सोमं।वरुणः।धृतऽव्रतः।अश्विऽभ्यां।उषसा।सऽजूः।।३०।।त्वं।अग्ने।वसून्।इह।रुद्रान्।आ
दित्यान्।उत।यज।सुऽअध्वरं।जनं।मनुऽजातं।घृतऽप्रुषं।।श्रुष्टीऽवानः।हि।दाशुषे।देवाः।अग्ने।वि
ऽचेतसः।तान्।रोहित्ऽअश्व।गिर्वणः।त्रयःऽत्रिंशतं।आ।वह।।प्रियमेधऽवत्।अत्रिऽवत्।जातऽ ५४

© Dharmartha Trust J&K. Digitized by eGangotri

वेदः । विरूपऽवत् । अंगिरस्वत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवं ॥ महिकेरवः । ऊतये । प्रियऽमे
धाः । अहूषत । राजंतं । अध्वराणां । अग्निं । शुक्रेण । शोचिषा ॥ घृतऽआहवन । संत्य । इमाः । ऊं इति ।
सु । श्रुधि । गिरः । याभिः । कण्वस्य । सूनवः । हवंते । अवसे । त्वा ॥ ५ ॥ त्वां । चित्रश्रवःऽतम । ह
वंते । विक्षु । जंतवः । शोचिःऽकेशं । पुरुऽप्रिय । अग्ने । हव्याय । वोळ्हवे ॥ नि । त्वा । होतारं । ऋत्वि
जं । दधिरे । वसुवित्ऽतमं । श्रुत्ऽकर्णं । सप्रथःऽतमं । विप्राः । अग्ने । दिविष्टिषु ॥ आ । त्वा । वि
प्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः । बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥
प्रातःऽयाव्नः । सहःऽकृत । सोमऽपेयाय । संत्य । इह । अद्य । दैव्यं । जनं । बर्हिः । आ । सादय । वसो

© Dharmartha Trust J&K. Digitized by eGangotri

१.प्र. इति ।। अर्वांचं । दैव्यं । जनं । अग्ने । यक्ष्व । सहूतिऽभिः । अयं । सोमः । सुऽदानवः । तं । पात । तिरःऽअह्न्यं

५५ ।।३२।। एषो इति । उषाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वां । अश्विना । बृहत् ।। या । दस्रा ।

त सिंधुऽमातरा । मनोतरा । रयीणां । धिया । देवा । वसुऽविदा ।। वच्यंते । वां । ककुहासः । जूर्णायां ।

45 अधि । विष्टपि । यत् । वां । रथः । विऽभिः । पतात् ।। हविषा । जारः । अपां । पिपर्ति । पपुरिः । नरा ।

पिता । कुटस्य । चर्षणिः । आऽदारः । वां । मतीनां । नासत्या । मतऽवचसा । पातं । सोमस्य । धृष्णुऽ

या ।।३३।। या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः । तां । अस्मे इति । रासाथां । इ

षं ।। आ । नः । नावा । मतीनां । यातं । पाराय । गंतवे । युंजाथां । अश्विना । रथं ।। अरित्रं । वां । दि ५५

© Dharmartha Trust J&K. Digitized by eGangotri

वः । पथ्या । तीर्थे । सिंधूनां । रथः । धिया । युयुजे । इंदवः ॥ दिवः । कण्वासः । इंदवः । वसु । सिंधूनां । प
दे । स्वं । वव्रिं । कुह । धित्सथः ॥ अभूत् । ऊं इति । भाः । ऊं इति । अंशवे । हिरण्यं । प्रति । सूर्यः । वि । अ
ख्यत् । जिह्वया । असितः ॥ १० ॥ अभूत् । ऊं इति । पारं । एतवे । पंथाः । ऋतस्य । साधुऽया । अद
र्शि । वि । स्रुतिः । दिवः ॥ तत्ऽतत् । इत् । अश्विनोः । अवः । जरिता । प्रति । भूषति । मदे । सोमस्य ।
पिप्रतोः ॥ वावसाना । विवस्वति । सोमस्य । पीत्या । गिरा । मनुष्वत् । शंभू इति शंऽभू । आ । ग
तं ॥ युवोः । उषाः । अनु । श्रियं । परिऽज्मनोः । उपऽआचरत् । ऋता । वनथः । अक्तुऽभिः ॥ उभा ।
पिबतं । अश्विना । उभा । नः । शर्म । यच्छतं । अविद्रियाभिः । ऊतिऽभिः ॥ १५ ॥ इति प्रथमाष्टके

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. तृतीयोध्यायः॥ॐ॥अयंदशप्रागाथंतुसहस्पोक्तशोपस्यंतूषश्चतुष्कमानुष्टुभंतूद्वृत्यंस
५६ ह्नोनासोयंनवागागायश्चौसस्तचोरोगघ्नंउपनिषदंस्योर्धऔहिवग्रौभिस्यंपंचोनो
सख्योहित्रिष्टुबंतमंगिराइंद्रतुत्यंपुत्रमिष्ठअभ्यध्यायत्लव्याइतींद्रमेवास्यपुत्रोजाय
तस्वंस्तुत्रयोदरयंसेत्रिष्टुभौन्यूषेकादशांसेत्रिष्टुभौमानोंसात्रिष्टुपूषध्यष्टमीनव
मीचदिवश्विदष्टौजागतंघेषप्रषट्समंहिष्ठायनूचिंनवनोधागोतमआग्नेयंहिचतु
स्त्रिष्टुबंतंययाइत्सतत्वैश्वानरीयंवन्हिंपंचास्माइदुषोक्तशौ॥५॥ॐ॥अयं।वां।मधुम
त्ऽतमः।सुतः।सोमः।ऋतऽवृधा।तं।अश्विना।पिबतं।तिरः।अन्ह्यं।धत्तं।रत्नानि।दाशु ५६

© Dharmartha Trust J&K. Digitized by eGangotri

पो। त्रिऽवंधुरेण। त्रिऽवृता। सुऽपेशसा। रथेन। आ। यातं। अश्विना। कण्वाः। सः। वां। ब्रह्म। कृण्वंति।
अध्वरे। तेषां। सु। शृणुतं। हवं। अश्विना। मधुमत्ऽतमं। पातं। सोमं। ऋतऽवृधा। अथ। अद्य। द-
स्रा। वसु। बिभ्रता। रथे। दाश्वांसं। उप। गच्छतं। त्रिऽसधस्थे। बर्हिषि। विश्वऽवेदसा। मध्वा। यज्ञं।
मिमिक्षतं। कण्वासः। वां। सुतऽसोमाः। अभिऽद्यवः। युवां। हवंते। अश्विना। याभिः। कण्वं। अभि-
ष्टिऽभिः। प्र। आवतं। युवं। अश्विना। ताभिः। सु। अस्मान्। अवतं। शुभः। पती इति। ॥ पातं सोममृ
तावृधा ॥ ऽ ॥ सुऽदासे ॥ ० दस्रा वसु बिभ्नता रथे ॥ दक्षः। वहतं। अश्विना। रयिं। समुद्रात्। उत।
वा। दिवः। परि। अस्मे इति। धत्तं। पुरुऽस्पृहं। यत्। नासत्या। पराऽवति। यत्। वा। स्थः। अधि। तुर्वे

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ग॰
४०
47

तौ । आ । नः । रथेन । सुऽवृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मिऽभिः ॥ अर्वाञ्चा । वाम् । सप्तयः । अध्व
रऽश्रियः । वहन्तु । सवना । इत् । उप । इषम् । पृञ्चन्ता । सुऽकृते । सुऽदानवे । आ । बर्हिः । सीदतम् । नरा ॥ ते
न । नासत्या । आ । गतम् । रथेन । सूर्यऽत्वचा । येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोम
स्य । पीतये ॥ उक्थेभिः । अर्वाक् । अवसे । पुरुवसू इति पुरुऽवसू । अर्कैः । च । नि । ह्वयामहे ॥ श
श्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना ॥ सह । वामेन । नः । उषः ।
वि । उच्छ । दुहितः । दिवः । सह । द्युम्नेन । बृहता । विभाऽवरि । राया । देवि । दास्वती ॥ अश्वऽवतीः ।
गोऽमतीः । विश्वऽसुविदः । भूरि । च्यवन्त । वस्तवे । उत् । ईरय । प्रति । मा । सूनृताः । उषः । चोद । रा ४७

© Dharmartha Trust J&K. Digitized by eGangotri

घः।मघोनां।।उवास।उषाः।उच्छात्।च।नु।देवी।जीरा।रथानां।ये।अस्याः।आऽचरणेषु।दध्रि
रे।समुद्रे।न।श्रवस्यवः।।उषः।ये।ते।प्र।यामेषु।युंजते।मनः।दानाय।सूरयः।अत्र।अह।
तत्।कण्वः।एषां।कण्वऽतमः।नाम।गृणाति।नृणां।।आ।घ।योषाऽइव।सूनरी।उषाः।या
ति।प्रऽभुंजती।जरयंती।वृजनं।पत्ऽवत्।ईयते।उत्।पातयति।पक्षिणः।।वि।या।सृज
ति।समनं।वि।अर्थिनः।पदं।न।वेति।ओदती।वयः।नकिः।ते।पप्तिऽवांसः।आसते।विऽ
उष्टौ।वाजिनीऽवति।।एषा।अयुक्त।पराऽवतः।सूर्यस्य।उत्ऽअयनात्।अधि।
शतं।रथेभिः।सुऽभगा।उषाः।इयं।वि।याति।अभि।मानुषात्।।विश्वं।अस्याः।ननाम।चक्ष

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सेऽजगत् । ज्योतिः । कृणोति । सूनरी । अप । द्वेषः । मघोनी । दुहिता । दिवः । उषाः । उच्छत् । अप । स्रिधः ॥
५८ उषः । आ । भाहि । भानुना । चंद्रेण । दुहितः । दिवः । आऽवहंती । भूरि । अस्मभ्यं । सौभगं । विऽउछंती ।
48 दिविष्टिषु ॥ विश्वस्य । हि । प्राणनं । जीवनं । त्वेइति । वि । यत् । उछसि । सूनरि । सा । नः । रथेन । बृह
ता । विभाऽवरि । श्रुधि । चित्रऽमघे । हवं ॥ ५ ॥ उषः । वाजं । हि । वंस्व । यः । चित्रः । मानुषे । जने । तेन ।
उपे । आ । वह । सुऽकृतः । अध्वरान् । ये । त्वा । गृणंति । वह्नयः ॥ विश्वान् । देवान् । आ । वह । सोमऽपीतये ।
अंतरिक्षात् । उषः । त्वं । सा । अस्मासु । धाः । गोऽमत् । अश्वऽवत् । उक्थ्यं । उषः । वाजं । सुऽवीर्यं ॥ य
स्याः । रुशंतः । अर्चयः । प्रति । भद्राः । अदृक्षत । सा । नः । रयिं । विश्वऽवारं । सुऽपेशसं । उषाः । ददातु । ५८

© Dharmartha Trust J&K. Digitized by eGangotri

सुऽग्म्यं ॥ या । चित् । हि । त्वां । ऋषयः । पूर्वे । ऊतये । जुहूरे । अवसे । महि । सा । नः । स्तोमान् । अभि । गृ
णीहि । राधसा । उषः । शुक्रेण । शोचिषा ॥ उषः । यत् । अद्य । भानुना । वि । द्वारौ । ऋणवः । दिवः । प्र ।
नः । यच्छतात् । अवृकं । पृथु । छर्दिः । प्र । देवि । गोऽमतीः । इषः ॥ सं । नः । राया । बृहता । विश्वऽपेशसा ।
मिमिक्ष्व । सं । इळाभिः । आ । सं । द्युम्नेन । विश्वऽतुरा । उषः । महि । सं । वाजैः । वाजिनीऽवति ॥ ८ ॥
उषः । भद्रेभिः । आ । गहि । दिवः । चित् । रोचनात् । अधि । वहंतु । अरुणऽप्सवः । उप । त्वा । सोमिनः ।
गृहं ॥ सुऽपेशसं । सुऽखं । रथं । यं । अधिऽअस्थाः । उषः । त्वं । तेन । सुऽश्रवसं । जनं । प्र । अव ।
अद्य । दुहितः । दिवः ॥ वयः । चित् । ते । पतत्रिणः । द्विऽपत् । चतुःऽपत् । अर्जुनि । उषः । प्र । आर

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ न् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥ विऽउच्छन्ती । हि । रश्मिऽभिः । विश्वम् । आऽभासि । रोचनम् । ताम् । त्वाम् ।
४९ उषः । वसुऽयवः । गीःऽभिः । कण्वाः । अहूषत ॥ ४ ॥ उत् । ऊं इति । त्यम् । जातऽवेदसम् । देवम् । वहन्ति । केतवः ।
दृशे । विश्वाय । सूर्यम् ॥ अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तुऽभिः । सूराय । विश्वऽचक्षसे ॥
49 अदृश्रम् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु । भ्राजन्तः । अग्नयः । यथा ॥ तरणिः । विश्वऽ
दर्शतः । ज्योतिःऽकृत् । असि । सूर्य । विश्वम् । आ । भासि । रोचनम् ॥ प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् ।
उत् । एषि । मानुषान् । प्रत्यङ् । विश्वम् । स्वः । दृशे ॥ ७ ॥ येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् ।
अनु । त्वम् । वरुण । पश्यसि ॥ वि । द्याम् । एषि । रजः । पृथु । अहा । मिमानः । अक्तुऽभिः । पश्यन् । जन्मा ४९

© Dharmartha Trust J&K. Digitized by eGangotri

नि। सूर्य॥ सप्त। त्वा। हरितः। रथे। वहंति। देव। सूर्य। शोचिःऽकेशं। विऽचक्षण॥ अयुक्त। सप्त। शुं
ध्युवः। सूरः। रथस्य। नप्त्यः। ताभिः। याति। स्वयुक्तिऽभिः॥ उत्। वयं। तमसः। परि। ज्योतिः। पश्यं
तः। उत्ऽतरं। देवं। देवऽत्रा। सूर्यं। अगन्म। ज्योतिः। उत्ऽतमं॥ उत्ऽयन्। अद्य। मित्रऽमहः। आऽरोह
न्। उत्ऽतरां। दिवं। हृत्ऽरोगं। मम। सूर्य। हरिमाणं। च। नाशय॥ शुकेषु। मे। हरिमाणं। रोपणाका
सु। दध्मसि। अथो इति। हारिद्रवेषु। मे। हरिमाणं। नि। दध्मसि॥ उत्। अगात्। अयं। आदित्यः।
विश्वेन। सहसा। सह। द्विषंतं। मह्यं। रंधयन्। मो इति। अहं। द्विषते। रधं॥ [illegible]॥ अभि। त्यं। मेषं। पुरु
ऽहूतं। ऋग्मियं। इंद्रं। गीःऽभिः। मदत। वस्वः। अर्णवं। यस्य। द्यावः। न। विऽचरंति। मानुषा। भुजे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰म॰ मंहिष्ठं। अभि। विप्रं। अर्चत॥ अभि। ईं। अवन्वन्। सुऽअभिष्टिं। ऊतयः। अंतरिक्षऽप्रां। तविषीभिः।
५० आऽवृतं। इंद्रं। दक्षासः। ऋभवः। मदऽच्युतं। शतऽक्रतुं। जवनी। सूनृता। आ। अरुहत्॥ त्वं। गो
त्रं। अंगिरःऽभ्यः। अवृणोः। अप। उत। अत्रये। शतऽदुरेषु। गातुऽवित्। ससेन। चित्। विऽमदाय।
अवहः। वसु। आजौ। अद्रिं। ववसानस्य। नर्तयन्॥ त्वं। अपां। अपिऽधाना। अवृणोः। अ
धारयः। पर्वते। दानुऽमत्। वसु। वृत्रं। यत्। इंद्र। शवसा। अवधीः। अहिं। आत्। इत्। सूर्यं। दिवि।
आ। अरोहयः। दृशे॥ त्वं। मायाभिः। अप। मायिनः। अधमः। स्वधाभिः। ये। अधि। शुप्तौ। अजु
ह्वत। त्वं। पिप्रोः। नृऽमनः। प्र। अरुजः। पुरः। प्र। ऋजिश्वानं। दस्युऽहत्येषु। आविथ॥ त्वं। कुत्सं। ५०

© Dharmartha Trust J&K. Digitized by eGangotri

शुष्णऽहत्येषु। आ। विथ। अरंधयः। अतिथिऽग्वाय। शंबरं। महांतं। चित्। अर्बुदं। नि। क्रमीः। पदा। स
नात्। एव। दस्युऽहत्याय। जज्ञिषे॥ त्वेइति। विश्वा। तविषी। सध्र्यक्। हिता। तव। राधः। सोमऽपी
थाय। हर्षते। तव। वज्रः। चिकिते। बाह्वोः। हितः। वृश्च। शत्रोः। अव। विश्वानि। वृष्ण्या॥ ॥ विजा
नीहि। आर्यान्। ये। च। दस्यवः। बर्हिष्मते। रंधय। शासत्। अव्रतान्। शाकी। भव। यजमा
नस्य। चोदिता। विश्वा। इत्। ता। ते। सधऽमादेषु। चाकन॥ ॥ अनुऽव्रताय। रंधयन्। अपऽव्रता
न्। आऽभूभिः। इंद्रः। श्नथयन्। अनाऽभुवः। वृद्धस्य। चित्। वर्धतः। द्यां। इनक्षतः। स्तवानः। वम्र
ः। वि। जघान। संऽदिहः॥ ॥ तक्षत्। यत्। ते। उशना। सहसा। सहः। वि। रोदसीइति। मज्मना।

© Dharmartha Trust J&K. Digitized by eGangotri

१.श. बाधते। शवः॥ आ। त्वा। वातस्य। नृऽमनः। मनःऽयुजः। आ। पूर्यमाणं। अवहन्। अभि। श्रवः॥ १०॥
५१ मंदिष्ट। यत्। उशने। काव्ये। सचा। इंद्रः। वंकू इति। वंकुऽतरा। अधि। तिष्ठति। उग्रः। ययिं। निः।
51 अपः। स्रोतसा। असृजत्। वि। शुष्णस्य। दृंहिताः। ऐरयत्। पुरः॥ आ। स्म। रथं। वृषऽपानेषु। ति
ष्ठसि। शार्यातस्य। प्रऽभृताः। येषु। मंदसे। इंद्र। यथा। सुतऽसोमेषु। चाकनः। अनर्वाणं। श्लोकं।
आ। रोहसे। दिवि॥ अददाः। अर्भां। महते। वचस्यवे। कक्षीवते। वृचयां। इंद्र। सुन्वते। मेना। अभ
वः। वृषणश्वस्य। सुक्रतो इति सुऽक्रतो॥ विश्वेत्ताते। सवनेषु। प्रऽवाच्या। इंद्रः। अभायि। सुऽ
ध्यः। निःऽरेके। पज्रेषु। स्तोमः। दुर्यः। न। यूपः। अश्वऽयुः। गव्युः। रथऽयुः। वसुऽयुः। इंद्रः। इत्। रायः। ५१

© Dharmartha Trust J&K. Digitized by eGangotri

यः।क्षयति।प्रऽयंता।इदं।नमः।वृषभाय।स्वऽराजे।सत्यऽशुष्माय।तवसे।अवाचि।अस्मिन्।
इंद्र।वृजने।सर्वऽवीराः।स्मत्।सूरिऽभिः।तव।शर्मन्।स्याम॥१५॥त्यं।सु।मेषं।महय।स्वःऽ
विदं।शतं।यस्य।सुऽभ्वः।साकं।ईरते।अत्यं।न।वाजं।हवनऽस्यदं।रथं।आ।इंद्रं।ववृत्यां।
अवसे।सुवृक्तिऽभिः॥सः।पर्वतः।न।धरुणेषु।अच्युतः।सहस्रंऽऊतिः।तविषीषु।ववृधे।इंद्रः।
यत्।वृत्रं।अवधीत्।नदीऽवृतं।उब्जन्।अर्णांसि।जर्हृषाणः।अंधसा॥सः।हि।द्वरः।द्वरिषु।
वव्रः।ऊधनि।चंद्रऽबुध्नः।मदऽवृद्धः।मनीषिऽभिः।इंद्रं।तं।अह्वे।सुऽअपस्यया।धिया।मंहिष्ठऽरातिं।
सः।हि।पप्रिः।अंधसः॥आ।यं।पृणंति।दिवि।सद्मऽबर्हिषः।समुद्रं।न।सुऽभ्वः।स्वाः।अभि

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. ष्टयः । तं । स्वऽसः ऽहसो । अनु । तस्थुः । ऊतयः । शुष्माः । इंद्रं । अवाताः । अकुतःऽप्सवः ।। अभि । स्वऽवृष्टिं । म
५२ दे । अस्य । युध्यतः । रघ्वीःऽइव । प्रवणे । सस्रुः । ऊतयः । इंद्रः । यत् । वज्री । धृषमाणः । अंधसा । भिन
52 त् । वलस्य । परिधीन्ऽइव । त्रितः ।। ५ ।। परि । ईं । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः ।
बुध्नं । आ । अशयत् । यत्र । वृत्रस्य । यत् । प्रवणे । दुःऽगृभिश्वनः । निऽजघंथ । हन्वोः । इंद्र । तन्यतुं ।। ह्रदं ।
न । हि । त्वा । निऽऋषंति । ऊर्मयः । ब्रह्माणि । इंद्र । तव । यानि । वर्धना । त्वष्टा । चित् । ते । युज्यं । वदृधे ।
शवः । ततक्ष । वज्रं । अभिभूतिऽओजसं ।। जघन्वान् । ऊं इति । हरिऽभिः । संभृतक्रतो इति संभृत
ऽक्रतो । इंद्र । वृत्रं । मनुषे । गातुऽयन् । अपः । अयच्छथाः । बाह्वोः । वज्रं । आयसं । अधारयः । दि ५२

© Dharmartha Trust J&K. Digitized by eGangotri

नि। आ। सूर्यं। दृशे॥ बृहत्। स्वऽचंद्रं। अमऽवत्। यत्। उक्थ्यं। अकृण्वत। भियसा। रोहणं। दिवः। यत्।
मानुषऽप्रधनाः। इंद्रं। ऊतयः। स्वः। नृऽसाचः। मरुतः। अमदन्। अनु॥ द्यौः। चित्। अस्य। अमऽवा
न्। अहेः। स्वनात्। अयोयवीत्। भियसा। वज्रः। इंद्र। ते। वृत्रस्य। यत्। बद्बधानस्य। रोदसीइति।
मदे। सुतस्य। शवसा। अभिनत्। शिरः॥१३॥ यत्। इत्। नु। इंद्र। पृथिवी। दशऽभुजिः। अहानि।
विश्वा। ततनंत। कृष्टयः। अत्र। अह। ते। मघऽवन्। विऽश्रुतं। सहः। द्यां। अनु। शवसा। बर्हणा। भुव हः
त्॥ त्वं। अस्य। पारे। रजसः। विऽओमनः। स्वभूतिऽओजाः। अवसे। धृषत्ऽमनः। चकृषे। भूमिं।
प्रतिऽमानं। ओजसः। अपः। स्वरिति स्वः। परिऽभूः। एषि। आ। दिवं॥ त्वं। भुवः। प्रतिऽमानं। पृ
© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. थिव्याः। ऋष्वः। वीरस्य। बृहतः। पतिः। भूः। विश्वं। आ। अप्राः। अंतरिक्षं। महिऽत्वा। सत्यं। अद्धा।
५२ नकिः। अन्यः। त्वाऽवान्॥ न। यस्य। द्यावापृथिवी इति। अनु। व्यचः। न। सिंधवः। रजसः। अं
53 तं। आनशुः। न। उत। स्वऽवृष्टिं। मदे। अस्य। युध्यतः। एकः। अन्यत्। चकृषे। विश्वं। आनुषक्॥
आर्चन्। अत्र। मरुतः। सस्मिन्। आजौ। विश्वे। देवासः। अमदन्। अनु। त्वा। वृत्रस्य। यत्। भृ
ष्टिऽमता। वधेन। नि। त्वं। इंद्र। प्रति। आनं। जघंथ॥ १५॥ नि। ऊं इति। सु। वाचं। प्र। महे। भरा
महे। गिरः। इंद्राय। सदने। विवस्वतः। नु। चित्। हि। रत्नं। ससतांऽइव। अविदत्। न। दुःऽस्तु
तिः। द्रविणःऽदेषु। शस्यते। दुरः। अश्वस्य। दुरः। इंद्र। गोः। असि। दुरः। यवस्य। वसुनः। इ ५२

नः। पतिः। शिक्षा। नरः। प्रऽदिवः। अकामऽकर्शनः। सखा। सखिऽभ्यः। तं। इदं। गृणीमसि॥ श
चीऽवः। इंद्र। पुरुऽकृत्। द्युमत्ऽतम। तव। इत्। इदं। अभितः। चेकिते। वसु। अतः। संऽगृभ्य। अभिऽ
भूते। आ। भर। मा। त्वाऽयतः। जरितुः। कामं। ऊनयीः। एभिः। द्युऽभिः। सुऽमनाः। एभिः। इंदुऽभिः। नि
ःऽरुंधानः। अमतिं। गोभिः। अश्विना। इंद्रेण। दस्युं। दरयंतः। इंदुऽभिः। युतऽद्वेषसः। सं। इषा। र
भेमहि॥ सं। इंद्र। राया। सं। इषा। रभेमहि। सं। वाजेभिः। पुरुऽचंद्रैः। अभिद्युऽभिः। सं। देव्या। प्रऽम
त्या। वीरऽशुष्मया। गोऽअग्रया। अश्वऽवत्या। रभेमहि॥ ५॥ ते। त्वा। मदाः। अमदन्। तानि। वृ
ष्ण्या। ते। सोमासः। वृत्रऽहत्येषु। सत्ऽपते। यत्। कारवे। दश। वृत्राणि। अप्रति। बर्हिष्मते।

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. नि।सहस्राणि।बर्हयः॥युधा।युधं।उप।घ।इत्।एषि।धृष्णुया।पुरा।पुरं।सं।इदं।हंसि।ओज
५४ सा।नम्या।यत्।इंद्र।सख्या।पराऽवति।निऽबर्हयः।नमुचिं।नाम।मायिनं॥त्वं।करंजं।उ
त।पर्णयं।वधीः।तेजिष्ठया।अतिथिऽग्वस्य।वर्तनी।त्वं।शता।वंगृदस्य।अभिनत्।पुरः।
54 अनानुऽदः।परिऽसूताः।ऋजिश्वना॥त्वं।एतान्।जनऽराज्ञः।द्विः।दश।अबंधुना।सुऽश्रव
सा।उपऽजग्मुषः।षष्टिं।सहस्रा।नवतिं।नव।श्रुतः।नि।चक्रेण।रथ्या।दुःऽपदा।अवृणक्॥
त्वं।आविथ।सुऽश्रवसं।तव।ऊतिऽभिः।तव।त्रामऽभिः।इंद्र।तूर्वयाणं।त्वं।अस्मै।कुत्सं।अ
तिथिऽग्वं।आयुं।महे।राज्ञे।यूने।अरंधनायः॥ये।उत्ऽऋचि।इंद्र।देवऽगोपाः।सखायः।ते। ५४

© Dharmartha Trust J&K. Digitized by eGangotri

शिवऽतमाः।अस्मा।त्वां।सोषाम।त्वया।सुऽवीराः।द्राघीयः।प्रऽतरं।दधानाः॥६॥मा।नः।अस्मि
न्।मघऽवन्।पृत्ऽसु।अंहसि।नहि।ते।अंतः।शवसः।परिऽनशे।अक्रंदयः।नद्यः।रोरुवत्।वना।
कृथा।न।क्षोणीः।भियसा।सं।आरत॥अर्च।शक्राय।शाकिने।शचीऽवते।शृण्वंतं।इंद्रं।महय
न्।अभि।स्तुहि।यः।धृष्णुना।शवसा।रोदसी इति।उभे इति।वृषा।वृषऽत्वा।वृषभः।निऽऋंजते॥
अर्च।दिवे।बृहते।शूष्यं।वचः।स्वऽक्षत्रं।यस्य।धृषतः।धृषत्।मनः।बृहत्ऽश्रवाः।असुरः।ब
र्हणा।कृतः।पुरः।हरिऽभ्यां।वृषभः।रथः।हि।सः॥त्वं।दिवः।बृहतः।सानु।कोपयः।अव।त्मना।
१.४१. धृषता।शंबरं।भिनत्।यत्।मायिनः।व्रंदिनः।मंदिना।धृषत्।शितां।गभस्तिं।अशनिं।पृ

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. न्यसि ॥ नि । यत् । वृणक्षि । श्वसनस्य । मूर्द्धनि । शुष्णस्य । चित् । व्रंदिनः । रोरुवत् । वना । प्राची
५५ नेन । मनसा । बर्हणाऽवता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि ॥ ५ ॥ त्वं । आविथ । नर्य्यं ।
तुर्वशं । यदुं । त्वं । तुर्वीतिं । वय्यं । शतक्रतो इति शतऽक्रतो । त्वं । रथं । एतशं । कृत्व्ये । धने । त्वं । पुरः ।
55 नवतिं । दम्भयः । नव ॥ सः । घ । राजा । सत्ऽपतिः । शूशुवत् । जनः । रातऽहव्यः । प्रति । यः । शासं
इन्वति । उक्था । वा । यः । अभिऽगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥ असं
मं । क्षत्रं । असमा । मनीषा । प्र । सोमऽपाः । अपसा । सन्तु । नेमे । ये । ते । इन्द्र । ददुषः । वर्धयन्ति ।
महि । क्षत्रं । स्थविरं । वृष्ण्यं । च ॥ तुभ्य । इत् । एते । बहुलाः । अद्रिऽदुग्धाः । चमूऽसदः । चमसाः । ५५

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रऽपानाः। वि। अश्नुहि। तर्पय। कामं। एषां। अथ। मनः। वसुऽदेयाय। कृष्व॥ अपां। अतिष्ठत्। धरुणऽ
ह्वरं। तमः। अंतः। वृत्रस्य। जठरेषु। पर्वतः। अभि। ईं। इंद्रः। नद्यः। वव्रिणा। हिताः। विश्वाः। अनुऽस्थाः।
प्रवणेषु। जिघ्नते॥ सः। शेऽवृधं। अधि। धाः। द्युम्नं। अस्मे इति। महि। क्षत्रं। जनाषाट्। इंद्र। तव्यं। र
क्ष। च। नः। मघोनः। पाहि। सूरीन्। राये। च। नः। सुऽअपत्यै। इषे। धाः॥१०॥ दिवः। चित्। अस्य। व
रिमा। वि। पप्रथे। इंद्रं। न। मह्ना। पृथिवी। चन। प्रति। भीमः। तुविष्मान्। चर्षणिऽभ्यः। आऽतपः। शि
शीते। वज्रं। तेजसे। न। वंसगः॥ सः। अर्णवः। न। नद्यः। समुद्रियः। प्रति। गृभ्णाति। विऽश्रिताः। व
रीमऽभिः। इंद्रः। सोमस्य। पीतये। वृषऽयते। सनात्। सः। युध्मः। ओजसा। पनस्यते॥ त्वं। तं। इंद्र।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰म॰ पर्वतं । न । भोजसे । महः । नृम्णस्य । धर्मणां । इरज्यसि ॥ प्र । वीर्येण । देवता । अति । चेकिते । वि
५६ श्वस्मै । उग्रः । कर्मणे । पुरःऽहितः ॥ सः । इत् । वने । नमस्युऽभिः । वचस्यते । चारु । जनेषु । प्रऽ
ब्रुवाणः । इन्द्रियं । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनां । मघऽवा । यत् । इन्वति ॥ सः ।
इत् । महानि । सम्ऽइथानि । मज्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः । अध । चन । श्रत् । दध
ति । त्विषिऽमते । इन्द्राय । वज्रं । निघनिऽघ्नते । वधं ॥ ३१ ॥ सः । हि । श्रवस्युः । सदनानि । कृत्रि
मा । क्ष्मया । वृधानः । ओजसा । विऽनाशयन् । ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे ।
अव । सुऽक्रतुः । सर्तवै । अपः । सृजत् ॥ दानाय । मनः । सोमऽपावन् । अस्तु । ते । अर्वाञ्चा । ह ५६

56

© Dharmartha Trust J&K. Digitized by eGangotri

रीइति। वृंदन्ऽश्रुत। आ। रुधि। यमिष्ठासः। सारथयः। यः। इंद्र। ते। न। त्वा। केताः। आ। दभ्नुवंति। भू
र्णयः॥ अप्नःऽक्षितं। वसु। बिभर्षि। हस्तयोः। अषाळ्हं। सहः। तन्वि। श्रुतः। दधे। आऽवृतासः। अ
वतासः। न। कर्तृऽभिः। तनूषु। ते। क्रतवः। इंद्र। भूरयः॥ २०॥ एषः। प्र। पूर्वीः। अव। तस्य। चम्रिषः।
अत्यः। न। योषां। उत्। अयंस्त। भुर्वणिः। दक्षं। महे। पाययते। हिरण्ययं। रथं। आऽवृत्य। हरि
योगं। ऋभ्वसं॥ तं। गूर्तयः। नेमन्ऽइषः। परीणसः। समुद्रं। न। संऽचरणे। सनिष्यवः। पतिं। दक्ष
स्य। विदथस्य। नु। सहः। गिरिं। न। वेनाः। अधि। रोह। तेजसा॥ सः। तुर्वणिः। महान्। अरेणु। पौं
स्ये। गिरेः। भृष्टिः। न। भ्राजते। तुजा। शवः। येन। शुष्णं। मायिनं। आयसः। मदे। दुध्रः। आभृषु।

© Dharmartha Trust J&K. Digitized by eGangotri

प०ग्र० रमयन्न। नि। दामनि। देवी। यदि। नविषी। त्वाऽवृधा। कुत्सये। इंद्र। निऽसक्ति। उपसां। न। सूर्यः॥१०॥ योध

५० स्नुना। शवसा। बाधते। नमः। इयर्ति। रेणुं। बृहन्। अर्हरिऽस्वनिः। वियन्। तिरः। धरुणं। अच्युतं।

रजः। अतिस्थिपः। दिवः। आऽता। सु। बर्हणा। स्वःऽमीळ्हे। यत्। मदे। इंद्र। हर्ष्या। अहन्। वृत्रं। निः। अपां।

57 औब्जः। अर्णवं॥ त्वं। दिवः। धरुणं। धिषे। ओजसा। पृथिव्याः। इंद्र। सदनेषु। माहिनः। त्वं। सुतस्य। म

दे। अरिणाः। अपः। वि। वृत्रस्य। समया। पाष्या। अरुजः॥१३॥ न। मंहिष्ठाय। बृहते। बृहतऽरये। स

त्यऽशुष्माय। तवसे। मतिं। भरे। अपांऽइव। प्रवणे। यस्य। दुःऽधरं। राधः। विश्वऽआयु। शवसे। अ

पऽवृतं॥ अध। ते। विश्वं। अनु। ह। असत्। इष्टये। आपः। निम्नाऽइव। सवना। हविष्मतः। यत्। पर्वते। ५०

ना । संऽअशीत । हर्यतः । इंद्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥ अस्मै । भीमाय । नमसा । सं । अध्वरे । उ
षः । न । शुभ्रे । आ । भर । पनीयसे । यस्य । धाम । श्रवसे । नाम । इंद्रियं । ज्योतिः । अकारि । हरितः । न ।
अयसे ॥ इमे । ते । इंद्र । ते । वयं । पुरुऽस्तुत । ये । त्वा । आऽरभ्य । चरामसि । प्रभुवसो इति प्रभुऽवसो । न
हि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःऽइव । प्रति । नः । हर्य । तत् । वचः ॥ भूरि । ते । इंद्र । वीर्यं । त
व । स्मसि । अस्य । स्तोतुः । मघऽवन् । कामं । आ । पृण । अनु । ते । द्यौः । बृहती । वीर्यं । मम । इयं । च । ते । पृ
थिवी । नेमे । ओजसे । ० त्वंतमिंद्रपर्वतं । महां । उरुं । वज्रेण । वज्रिन् । पर्वऽशः । चकर्तिथ । अव । असृजः ।
निऽवृताः । सर्तवै । अपः । सत्रा । विश्वं । दधिषे । केवलं । सहः ॥ २२ ॥ नु । चित् । सहःऽजाः । अमृतः । नि ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ग॰ तुंदते।होता।यत्।दूतः।अभवत्।विवस्वतः।वि।साधिष्ठेभिः।पथिऽभिः।रजः।ममे।आ।देवऽता
५८ ता।हविषा।विवासति॥आ।स्वं।अद्म।युवमानः।अजरः।तृषु।अविष्यन्।अतसेषु।तिष्ठति।
अत्यः।न।पृष्ठं।प्रुषितस्य।रोचते।दिवः।न।सानु।स्तनयन्।अचिक्रदत्॥क्राणा।रुद्रेभिः।
58 वसुऽभिः।पुरःऽहितः।होता।निऽसत्तः।रयिषाट्।अमर्त्यः।रथः।न।विक्षु।ऋंजसानः।आयु
षु।वि।आनुषक्।वार्या।देवः।ऋण्वति॥वि।वातऽजूतः।अतसेषु।तिष्ठते।वृथा।जुहूभिः।सृ
ण्या।तुविऽस्वनिः।तृषु।यत्।अग्ने।वनिनः।वृषऽयसे।कृष्णं।ते।एम।रुशत्ऽऊर्मे।अज शिव
र॥तपुःऽजंभः।वने।आ।वातऽचोदितः।यूथे।न।साह्वान्।अव।वाति।वंसगः॥अभिऽव्रजन्। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

अक्षितं। पाजसा। रजः। स्थातुः। चरथं। भयते। पतत्रिणः॥ ५॥ दधुः। त्वा। भृगवः। मानुषेषु। आ।
रयिं। न। चारुं। सुऽहवं। जनेभ्यः। होतारं। अग्ने। अतिथिं। वरेण्यं। मित्रं। न। शेवं। दिव्याय। जन्म
ने। होतारं। सप्त। जुह्वः। यजिष्ठं। यं। वाघतः। वृणते। अध्वरेषु। अग्निं। विश्वेषां। अरतिं। वसूनां।
सपर्यामि। प्रयसा। यामि। रत्नं॥ अच्छिद्रा। सूनो इति। सहसः। नः। अद्य। स्तोतृऽभ्यः। मित्रऽमहः।
शर्म। यच्छ। अग्ने। गृणंतं। अंहसः। उरुष्य। ऊर्जः। नपात्। पूःऽभिः। आयसीभिः॥ भव। वरूथं।
गृणते। विभाऽवः। भव। मघऽवन्। मघवत्ऽभ्यः। शर्म। उरुष्य। अग्ने। अंहसः। गृणंतं। प्रातः।
मक्षु। धियाऽवसुः। जगम्यात्॥ ९॥ वयाः। इत्। अग्ने। अग्नयः। ते। अन्ये। त्वे इति। विश्वे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ अमृताः।मादयंते।वैश्वानर।नाभिः।असि।क्षितीनां।स्थूणाऽइव।जनान्।उपऽमित्।ययंथ॥मू
५९ र्धा।दिवः।नाभिः।अग्निः।पृथिव्याः।अथ।अभवत्।अरतिः।रोदस्योः।तं।त्वा।देवासः।अजनयंत।
देवं।वैश्वानर।ज्योतिः।इत्।आर्याय॥आ।सूर्ये।न।रश्मयः।ध्रुवासः।वैश्वानरे।दधिरे।अग्ना।
59 वसूनि।या।पर्वतेषु।ओषधीषु।अप्ऽसु।या।मानुषेषु।असि।तस्य।राजा॥बृहतीइवेतिबृह
तीऽइव।सूनवे।रोदसीइति।गिरः।होता।मनुष्यः।न।दक्षः।स्वःऽवते।सत्यऽशुष्माय।पूर्वीः।वै
श्वानराय।नृऽतमाय।यह्वीः॥दिवः।चित्।ते।बृहतः।जातऽवेदः।वैश्वानर।प्र।रिरिचे।महिऽत्वं। राम
राजा।कृष्टीनां।असि।मानुषीणां।युधा।देवेभ्यः।वरिवः।चकर्थ॥प्र।नु।महिऽत्वं।वृषभस्य।वो ५९

© Dharmartha Trust J&K. Digitized by eGangotri

वं। यं। पूरवः। वृत्रऽहनं। सचंते। वैश्वानरः। दस्युं। अग्निः। जघन्वान्। अधूनोत्। काष्ठाः। अव। शंब
रं। भेत्॥ वैश्वानरः। महिम्ना। विश्वऽकृष्टिः। भरत्ऽवाजेषु। यजतः। विभाऽवा। शातऽवनेये। शति
नीभिः। अग्निः। पुरुऽनीथे। जरते। सूनृताऽवान्॥ वह्निं। यशसं। विदथस्य। केतुं। सुप्रऽअव्यं।
दूतं। सद्यःऽअर्थं। द्विऽजन्मानं। रयिंऽइव। प्रऽशस्तं। रातिं। भरत्। भृगवे। मातरिश्वा॥ अस्य। शासुः।
उभयासः। सचंते। हविष्मंतः। उशिजः। ये। च। मर्ताः। दिवः। चित्। पूर्वः। नि। असादि। होता। आऽपृ
च्छ्यः। विश्पतिः। विक्षु। वेधाः॥ तं। नव्यसी। हृदः। आ। जायमानं। अस्मत्। सुऽकीर्तिः। मधुऽजिह्वं।
अश्याः। यं। ऋत्विजः। वृजने। मानुषासः। प्रयस्वंतः। आयवः। जीजनंत॥ उशिक्। पावकः। वसुः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ मानुषेषु । वरेण्यः ॥ होता । अधायि । विक्षु । दमूनाः ॥ गृहऽपतिः । दमे । आ । अग्निः । भुवत् ।
६० रयिऽपतिः ॥ रयीणां ॥ तं । त्वा । वयं । पते । अग्ने । रयीणां ॥ प्र । शंसामः । मतिऽभिः । गो
तमासः ॥ आशुं । न । वाजंऽभरं । मर्जयंतः ॥ प्रातर्मक्षू धियावसुर्जगम्यात् । २६ ॥ अस्मै ।
इत् । ऊं इति । प्रातऽवसे । तुराय । मघवः ॥ नाहमिं । स्तोमं । माहिनाय । ऋचीषमाय । अध्रिऽग
वे । ओहां । इंद्राय । ब्रह्माणि । राततऽतमा ॰ अस्मा इदु । प्रयःऽइव । प्र । यंसि । भरामि । आं
गूषं । बाधे । सुऽवृक्ति । इंद्राय । हृदा । मनसा । मनीषा । प्रत्नाय । पत्ये । धियः । मर्जयंत् शिव
ता ॰ यं । उपऽमां । स्वःऽसां । भरामि । आंगूषं । आस्येन । मंहिष्ठं । अच्छोक्तिऽभिः । मतीनां । ६०

60

सुवृक्तिऽभिः। सूरिं। ववृधध्यै। ० स्तोमं। सं। हिनोमि। रथं। न। तष्टाऽइव। तत्ऽसिनाय। गिरः। च। गि
र्वाहसे। सुऽवृक्ति। इंद्राय। विश्वम्ऽइन्वं। मेधिराय। ० सप्तिंऽइव। श्रवस्या। इंद्राय। अर्कं। जुह्वा। सं।
अंजे। वीरं। दानऽओकसं। वंदध्यै। पुरां। गूर्तऽश्रवसं। दर्माणं॥ २७॥ त्वष्टा। तक्षत्। वज्रं। स्वपःऽत
मं। स्वर्यं। रणाय। वृत्रस्य। चित्। विदत्। येन। मर्म। तुजन्। ईशानः। तुजता। कियेधाः। अस्य। इ
त्। ऊं इति। मातुः। सवनेषु। सद्यः। महः। पितुं। पपिऽवान्। चारु। अन्ना। मुषायत्। विष्णुः। पचतं।
सहीयान्। विध्यत्। वराहं। तिरः। अद्रिं। अस्ता। ० ग्नाः। चित्। देवऽपत्नीः। इंद्राय। अर्कं। अहिऽ
हत्ये। ऊवुरित्यूवुः। परि। द्यावा। पृथिवी इति। जभ्रे। उर्वी इति। न। अस्य। ते इति। महिमानं। परि। स्त

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ इतिस्तः।अस्य।इत्।एव।प्र।रिरिचे।महिऽत्वं।दिवः।पृथिव्याः।परि।अंतरिक्षात्।स्वऽराट्।इंद्रः।
६३ दमे।आ।विश्वऽगूर्तः।सुऽअरिः।अमत्रः।ववक्षे।रणाय॥ अस्येदेव। शवसा।शुषंतं।वि।वृश्च
त्।वज्रेण।वृत्रं।इंद्रः।गाः।न।व्राणाः।अवनीः।अमुंचत्।अभि।श्रवः।दावने।सऽचेताः॥१०॥
61 अस्येदु। त्वेषसा।रंत।सिंधवः।परि।यत्।वज्रेण।सीं।अयच्छत्।ईशानऽकृत्।दाशुषे।दशस्य
न्।तुर्वीतये।गाधं।तुर्वणिः।कः।इतिकः॥० अस्मा इदु प्र। भर।तूतुजानः।वृत्राय।वज्रं।ईशा
नः।कियेधाः।गोः।न।पर्व।वि।रद।तिरश्चा।इष्यन्।अर्णांसि।अपां।चरध्यै॥० अस्येदु।
प्र।ब्रूहि।पूर्व्याणि।तुरस्य।कर्माणि।नव्यः।उक्थैः।युधे।यत्।इष्णानः।आयुधानि।ऋ ६३

© Dharmartha Trust J&K. Digitized by eGangotri

घायमाणः । निःऽरिणा । नि । शत्रून् ॥ ० अस्य । इत् । ऊं इति । भिया । गिरयः । च । दृह्ळाः । द्यावा । च । भूम । जनु
षः । तुजेते इति । उपो इति । वेनस्य । जोगुवानः । ओणिं । सद्यः । भुवत् । वीर्याय । नोधाः ॥ ० अस्मा
इत् । ऊं इति । त्यत् । अनु । दायि । एषां । एकः । यत् । वव्ने । भूरेः । ईशानः । प्र । एतशं । सूर्ये । पस्पृधानं । सौव स २
श्व्ये । सुस्विं । आवत् । इन्द्रः ॥ एव । ते । हारिऽयोजना । सुऽवृक्ति । इन्द्र । ब्रह्माणि । गोतमासः । अक्रन् ।
आ । एषु । विश्वऽपेशसं । धियं । धाः ॥ ० ॥ २ ॥ इति प्रथमाष्टके चतुर्थोध्यायः ॥ प्रसन्तोना
त्वं नवरश्मे पंचोनामा हतं त्रिगुणं तं परमाग्नेयमिन्द्रा एप्श्वादशं परा शारःशा न्त्योहैवदं तद्धयि
र्वै नेषु श्रीणं ऋ॒ क्रो वनेमैकादशो पप्रदशानिका व्यारयिनौ पप्रयं तो नवगोतमोरा हुगणोगः

प.प्र. यत्रं तु सुषस्त्वपं चकान्तेकथाभि त्वागायत्रं तु हिरण्यके शोद्वादशायो त्त्रचौ त्रैष्टुभो ऽस्मिन्होपूर्वो
६२ ग्नयेवामध्यमायेथाहिषोळशेंद्रं पांक्तं हियाभित्वस्यां निपातिनोदध्यङ्मनुरथर्वा चेति।
॥५॥ प्र। मन्महे। शवसानाय। शूषं। आंगूषं। गिर्वणसे। अंगिरस्वत्। सुवृक्तिऽभिः। स्तुवते। ऋ
ग्मियाय। अर्चाम। अर्कं। नरे। विऽश्रुताय॥ प्र। वः। महे। महि। नमः। भरध्वं। आंगूष्यं। शवसा
नाय। साम। येन। नः। पूर्वे। पितरः। पदऽज्ञाः। अर्चंतः। अंगिरसः। गाः। अविंदन्॥ इंद्रस्य। अं
गिरसां। च। इष्टौ। विदत्। सरमा। तनयाय। धासिं। बृहस्पतिः। भिनत्। अद्रिं। विदत्। गाः। सं।
उस्रियाभिः। वावशंत। नरः॥ सः। सुऽस्तुभा। सः। स्तुभा। सप्त। विप्रैः। स्वरेण। अद्रिं। स्वर्यः। ६२

62

ऽः

नवऽग्वैः। सुरण्युऽभिः। फलिऽगं। इंद्र। शक्र। वलं। रवेण। दरयः। दशऽग्वैः॥ गृणानः। अंगिरऽभिः।
दस्म। वि। वः। उषसा। सूर्येण। गोभिः। अंधः। वि। भूम्याः। अप्रथयः। इंद्र। सानु। दिवः। रजः।
उपरं। अस्तभायः॥४॥ तत्। ऊं इति। प्रयक्ष्यऽतमं। अस्य। कर्म। दस्मस्य। चारुऽतमं। अ
स्ति। दंसः। उपऽह्वरे। यत्। उपराः। अपिन्वत्। मधुऽअर्णसः। नद्यः। चतस्रः॥ हिता। वि। वव्रे।
सनऽजा। सनीळे इति सऽनीळे। अयास्यः। स्तवमानेभिः। अर्कैः। भगः। न। मेने इति। परमे। वि
ऽओमन्। अधारयत्। रोदसी इति। सुऽदंसाः॥५॥ सनात्। दिवं। परि। भूम। विरूपे इति विऽरू
पे। पुनःऽभुवा। युवती इति। स्वेभिः। एवैः। कृष्णेभिः। अक्ता। उषाः। रुशत्ऽभिः। वपुःऽभिः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. आ। चरतः। अन्याऽअन्या॥ सनेमि। सख्यं। सुऽअपस्यमानः। सूनुः। दाधार। शवसा। सुऽदं
६२ साः। आमासु। चित्। दधिषे। पक्वं। अंतरिति। पयः। कृष्णासु। रुशत्। रोहिणीषु॥ सनात्।
सऽनीळाः। अवनीः। अवाताः। व्रता। रक्षंते। अमृताः। सहःऽभिः। पुरु। सहस्राः। जनयः। न।
63 पत्नीः। दुवस्यंति। स्वसारः। अह्रयाणं॥ १२॥ सनाऽयुवः। नमसा। नव्यः। अर्कैः। वसुऽयवः।
मतयः। दस्म। दद्रुः। पतिं। न। पत्नीः। उशतीः। उशंतं। स्पृशंति। त्वा। शवसाऽवन्। मनीषाः॥
सनात्। एव। तव। रायः। गभस्तौ। न। क्षीयंते। न। उप। दस्यंति। दस्म। द्युऽमान्। असि। क्रतुः।
मान्। इंद्र। धीरः। शिक्ष। शचीऽवः। तव। नः। शचीभिः॥ सनाऽयते। गोतमः। इंद्र। नव्यं। अत ६३

© Dharmartha Trust J&K. Digitized by eGangotri

नः।

सता।ब्रह्म।हरिऽयोजनाय।सुऽनीथाय।शवसा।नोधाः।१०।३।त्वं।महान्।इंद्र।यः।ह।शुष्मैः।
द्यावा।जज्ञानः।पृथिवी इति।अमे।धाः।यत्।ह।ते।विश्वा।गिरयः।चित्।अभ्वा।भिया।दृळ्हा
सः।किरणाः।न।ऐजन्॥आ।यत्।हरी इति।इंद्र।विऽव्रता।वेः।आ।ते।वज्रं।जरिता।बाह्वोः।
धात्।येन।अविहर्यतक्रतो इत्यविहर्यतऽक्रतो।अमित्रान्।पुरः।इष्णासि।पुरुऽहूत।पूर्वीः॥
त्वं।सत्यः।इंद्र।धृष्णुः।एतान्।त्वं।ऋभुक्षाः।नर्यः।त्वं।षाट्।त्वं।शुष्णं।वृजने।पृक्षे।आणौ।यू
ने।कुत्साय।द्युऽमते।सचा।अहन्॥त्वं।ह।त्यत्।इंद्र।चोदीः।सखा।वृत्रं।यत्।वज्रिन्।वृषऽ
कर्मन्।उभ्नाः।यत्।ह।शूर।वृषऽमनः।पराचैः।वि।दस्यून्।योनौ।अकृतः।वृथा।षाट्।०

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ हस्तदिंद्रा। अरिषण्यन्। हुब्हस्यां। चित्। मर्तीनां। अजुष्टौ। वि। अस्मत्। आ। काष्ठाः। अर्वते। वः।
६४ घनाऽइव। वज्रिन्। श्नथिहि। अमित्रान्॥ ५॥ त्वां। हस्तदिंद्रा। अर्णःऽसातौ। स्वःऽमीळ्हे। नरः।
आजा। हवंते। तव। स्वधाऽवः। इयं। आ। समऽमर्ये। ऊतिः। वाजेषु। अतसाय्या। भूत्॥ ६॥ वं हस्तदिं
64 द्रा। सप्त। युध्यन्। पुरः। वज्रिन्। पुरुऽकुत्साय। दर्दरितिर्दर्दः। बर्हिः। न। यत्। सुऽदासे। रथा। वर्क्।
अंहोः। राजन्। वरिवः। पूरवे। करिति कः॥ त्वं। त्यां। नः। इंद्र। देव। चित्रां। इषं। आपः। न। पीपयः। प
रिऽज्मन्। यया। शूर। प्रति। अस्मभ्यं। यंसि। त्मनं। ऊर्जं। न। विश्वध। क्षरध्यै॥ अकारि। ते। इं
द्र। गोतमेभिः। ब्रह्माणि। आऽउक्ता। नमसा। हरिऽभ्यां। सुऽपेशसं। वाजं। आ। भर। नः॥ १०॥ ८॥ ६४

© Dharmartha Trust J&K. Digitized by eGangotri

वृष्णे। शर्धाय। सुऽमखाय। वेधसे। नोधः। सुऽवृक्तिं। प्र। भर। मरुत्ऽभ्यः। अपः। न। धीरः। मनसा।
सुऽहस्त्यः। गिरः। सं। अंजे। विदथेषु। आऽभुवः॥ ते। जज्ञिरे। दिवः। ऋष्वासः। उक्षणः। रुद्रस्य। म
र्याः। असुराः। अरेपसः। पावकासः। शुचयः। सूर्याःऽइव। सत्वानः। न। द्रप्सिनः। घोरऽवर्पसः॥
युवानः। रुद्राः। अजराः। अभोक्ऽहनः। ववक्षुः। अध्रिऽगावः। पर्वताःऽइव। दृळ्हा। चित्। विश्वा। भु
वनानि। पार्थिवा। प्र। च्यावयंति। दिव्यानि। मज्मना॥ चित्रैः। अंजिऽभिः। वपुषे। वि। अंजते। वक्षः
ऽसु। रुक्मान्। अधि। येतिरे। शुभे। अंसेषु। एषां। नि। मिमृक्षुः। ऋष्टयः। साकं। जज्ञिरे। स्वधया।
दिवः। नरः॥ ईशानऽकृतः। धुनयः। रिशादसः। वातान्। विऽद्युतः। तविषीभिः। अक्रत। दुहंति। ऊ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प॰ धः । दिव्यानि । धूतयः । भूमिं । पिन्वंति । पयसा । परिऽज्रयः ॥ २ ॥ पिन्वंति । अपः । मरुतः । सुऽदानवः । प

६५ यः । घृतऽवत् । विदथेषु । आऽभुवः । अत्यं । न । मिहे । वि । नयंति । वाजिनं । उत्सं । दुहंति । स्तनयंतं । अक्षि

तं ॥ महिषासः । मायिनः । चित्रऽभानवः । गिरयः । न । स्वऽतवसः । रघुऽस्यदः । मृगाःऽइव । हस्तिनः ।

65 खादथ । वना । यत् । आरुणीषु । तविषीः । अयुग्ध्वं ॥ सिंहाःऽइव । नानदति । प्रऽचेतसः । पिशाःऽइव ।

सुऽपिशः । विश्वऽवेदसः । क्षपः । जिन्वंतः । पृषतीभिः । ऋष्टिऽभिः । सं । इत् । सऽबाधः । शवसा । अहिऽ

मन्यवः ॥ रोदसी इति । आ । वदत । गणऽश्रियः । नृऽसाचः । शूराः । शवसा । अहिऽमन्यवः । आ । वंधुरे

षु । अमतिः । न । दर्शता । विद्युत् । न । तस्थौ । मरुतः । रथेषु । वः ॥ विश्वऽवेदसः । रयिऽभिः । संऽओकसः ६५

© Dharmartha Trust J&K. Digitized by eGangotri

सः । संऽमिश्लाः । तविषीभिः । विऽराप्शिनः । अस्तारः । इषुं । दधिरे । गभस्त्योः । अनंतऽशुष्माः । वृषऽखादयः । नरः ॥ ७ ॥ हिरण्ययेभिः । पविऽभिः । पयःऽवृधः । उत् । जिघ्नंते । आऽपथ्यः । न । पर्वतान् । मखाः । अयासः । स्वऽसृतः । ध्रुवऽच्युतः । दुध्रऽकृतः । मरुतः । भ्राजत्ऽऋष्टयः ॥ घृषुं । पावकं । वनिनं । विऽचर्षणिं । रुद्रस्य । सूनुं । हवसा । गृणीमसि । रजःऽतुरं । तवसं । मारुतं । गणं । ऋजीषिणं । वृषणं । सश्चत । श्रिये ॥ प्र । नु । सः । मर्तः । शवसा । जनान् । अति । तस्थौ । वः । ऊती । मरुतः । यं । आवत । अर्वत्ऽभिः । वाजं । भरते । धना । नृऽभिः । आऽपृच्छ्यं । क्रतुं । आ । क्षेति । पुष्यति ॥ चर्कृत्यं । मरुतः । पृत्ऽसु । दुस्तरं । द्युऽमंतं । शुष्मं । मघवत्ऽसु । धत्तन । धनऽस्पृतं । उक्थ्यं । विश्वऽचर्षणिं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ऋ. तोकं। पुष्येम। तनयं। शतं। हिमाः। नु। शिरं। मुहतः। वीरऽवंतं। अरतिऽसहं। रयिं। अस्मा। सु। धत्त। सहस्त्रिणं।
६६ शातिनं। नृभुऽवांसं॥१०॥८८॥ पश्चा। न। तायुं। गुहा। चतंतं। नमः। युजानं। नमः। वहंतं। सऽजोषाः। धी
राः। पदैः। अनु। ग्मन्। उप। त्वा। सीदन्। विश्वे। यजत्राः॥ ऋतस्य। देवाः। अनु। व्रता। गुः। भुवत्। परिष्टिः।
द्यौः। न। भूम। वर्धति। इं। आपः। पन्वा। सुऽशिश्विं। ऋतस्य। योना। गर्भे। सुऽजातं॥ पुष्टिः। न। रण्वा।
क्षितिः। न। पृथ्वी। गिरिः। न। भुज्म। क्षोदः। न। शंऽभु। अत्यः। न। अज्मन्। सर्गऽप्रतक्तः। सिंधुः। न। क्षो
दः। कः। ईं। वराते॥ जामिः। सिंधूनां। भ्राताऽइव। स्वस्रां। इभ्यान्। न। राजा। वनानि। अत्ति। यत्। वा
तऽजूतः। वना। वि। अस्थात्। अग्निः। ह। दाति। रोम। पृथिव्याः॥ श्वसिति। अप्सु। हंसः। न। सीदन्। ६६

66

© Dharmartha Trust J&K. Digitized by eGangotri

कृत्वा । चेतिष्ठः । विशां । उषःऽभुत् । सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा । विऽभुः । दूरेऽ
भाः ।। १ ।। रयिः । न । चित्रा । सूरः । न । संऽदृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः । तक्वा । न । भूर्
णिः । वना । सिसक्ति । पयः । न । धेनुः । शुचिः । विभाऽवा ।। दाधार । क्षेमं । ओकः । न । रण्वः । यवः ।
न । पक्वः । जेता । जनानां । ऋषिः । न । स्तुभ्वा । विक्षु । प्रऽशस्तः । वाजी । न । प्रीतः । वयः । दधाति ।।
दुरोकऽशोचिः । क्रतुः । न । नित्यः । जायाऽइव । योनौ । अरं । विश्वस्मै । चित्रः । यत् । अभ्राट् । श्वेतः ।
न । विक्षु । रथः । न । रुक्मी । त्वेषः । समत्ऽसु ।। सेनाऽइव । सृष्टा । अमं । दधाति । अस्तुः । न । दिद्यु
त् । त्वेषऽप्रतीका । यमः । ह । जातः । यमः । जनिऽत्वं । जारः । कनीनां । पतिः । जनीनां ।। तं । वः । च

© Dharmartha Trust J&K. Digitized by eGangotri

प॰त्र॰ राथा। वयं। वसत्या। अस्तं। न। गावः। नक्षंत। इद्धं। सिंधुः। न। क्षोदः। प्र। नीचीः। ऐनोत्। नवंत। गावः। स्वः।
६७ दृशीके॥१०॥ वनेषु। जायुः। मर्तेषु। मित्रः। वृणीते। श्रुष्टिं। राजाऽइव। अजुर्यं। क्षेमः। न। साधुः। क्रतुः।
न। भद्रः। भुवत्। सुऽआधीः। होता। हव्यऽवाट्॥ हस्ते। दधानः। नृम्णा। विश्वानि। अमे। देवान्। धात्।
67 गुहा। निऽसीदन्॥ विदंति। ईं। अत्र। नरः। धियंऽधाः। हृदा। यत्। तष्टान्। मंत्रान्। अशंसन्॥ अजः। न।
क्षां। दाधार। पृथिवीं। तस्तंभ। द्यां। मंत्रेभिः। सत्यैः॥ प्रिया। पदानि। पश्वः। नि। पाहि। विश्वऽआयुः। अ
ग्ने। गुहा। गुहं। गाः॥ यः। ईं। चिकेत। गुहा। भवंतं। आ। यः। ससाद। धारां। ऋतस्य॥ वि। ये। चृतंति।
ऋता। सपंतः। आत्। इत्। वसूनि। प्र। ववाच। अस्मै॥ वि। यः। वीरुत्ऽसु। रोधत्। महिऽत्वा। उत। प्रऽजाः। उत। प्रऽसूः। ६७

© Dharmartha Trust J&K. Digitized by eGangotri

उत। गृऽत्सु। अंतरिति॥ चित्तिः। अपां। दमे। विश्वऽआयुः। सद्मऽइव। धीराः। संऽमाय। चक्रुः।
॥११॥ श्रीणन्। उप। स्थात्। दिवं। भुरण्युः। स्थातुः। चरथं। अक्तून्। वि। ऊर्णोत्। परि। यत्।
एषां। एकः। विश्वेषां। भुवत्। देवः। देवानां। महिऽत्वा॥ आत्। इत्। ते। विश्वे। क्रतुं। जुषं
त। शुष्कात्। यत्। देव। जीवः। जनिष्ठाः। भजंत। विश्वे। देवऽत्वं। नाम। ऋतं। सपंतः। अ
मृतं। एवैः॥ ऋतस्य। प्रेषाः। ऋतस्य। धीतिः। विश्वऽआयुः। विश्वे। अपांसि। चक्रुः। यः।
तुभ्यं। दाशात्। यः। वा। ते। शिक्षात्। तस्मै। चिकित्वान्। रयिं। दयस्व॥ होता। निऽसत्तः।
मनोः। अपत्ये। सः। चित्। नु। आसां। पतिः। रयीणां॥ इच्छंत। रेतः। मिथः। तनूषु। सं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ग॰ जानत। स्वैः। दक्षैः। अमृताः॥ पितुः। न। पुत्राः। क्रतुं। जुषन्त। श्रोषन्। ये। अस्य। शासं। तुरासः। वि।
६८ रायः। और्णोत्। दुरः। पुरुऽक्षुः। पिपेश। नाकं। स्तृऽभिः। दमूनाः॥ ॥३२॥ शुक्रः। शुशुक्वान्। उषः। न।
जारः। पप्रा। समीचीइति सं॒ऽईची। दिवः। न। ज्योतिः। परि। प्रऽजातः। क्रत्वा। बभूथ। भुवः। देवानां।
नं४ पिता। पुत्रः। सन्। वेधाः। अदृप्तः। अग्निः। विऽजानन्। ऊधः। न। गोनां। स्वाद्म। पितूनां। जने। न। शेवः।
आऽहूर्यः। सन्। मध्ये। निऽसत्तः। रण्वः। दुरोणे॥ पुत्रः। न। जातः। रण्वः। दुरोणे। वाजी। न। प्रीतः।
विशः। वि। तारीत्। विशः। यत्। अह्वे। नृऽभिः। सऽनीडाः। अग्निः। देवऽत्वा। विश्वानि। अश्याः॥
नकिः। ते। एता। व्रता। मिनन्ति। नृऽभ्यः। यत्। एभ्यः। श्रुष्टिं। चकर्थ। तत्। तु। ते। दंसः। यत्। अहन्। ६८

© Dharmartha Trust J&K. Digitized by eGangotri

समानैः । नृऽभिः । यत् । युक्तः । विवेः । रपांसि ॥ उषः । न । जारः । विभाऽवा । उस्रः । संज्ञातऽरूपः । चि
केतत् । अस्मै । त्मना । वहंतः । दुरः । वि । ऋण्वन् । नवंत । विश्वे । स्वः । दृशीके ॥ १३ ॥ वनेम । पूर्वीः । अ
र्यः । मनीषा । अग्निः । सुऽशोकः । विश्वानि । अश्याः । आ । दैव्यानि । व्रता । चिकित्वान् । आ । मानु
षस्य । जनस्य । जन्म ॥ गर्भः । यः । अपां । गर्भः । वनानां । गर्भः । च । स्थातां । गर्भः । चरथां । अद्रौ
चित् । अस्मै । अंतः । दुरोणे । विशां । न । विश्वः । अमृतः । सुऽआधीः ॥ सः । हि । क्षपाऽवान् । अ
ग्निः । रयीणां । दाशत् । यः । अस्मै । अरं । सुऽउक्तैः । एता । चिकित्वः । भूम । नि । पाहि । देवानां ।
जन्म । मर्तान् । च । विद्वान् ॥ वर्धान् । यां । पूर्वीः । क्षपः । विऽरूपाः । स्थातुः । च । रथं । ऋतऽप्र

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰
६९

69

वीतं। अराधि। होता। स्वः। निऽसत्तः। कृण्वन्। विश्वानि। अपांसि। सत्या॥ गोषु। प्रऽशस्तिं। वनेषु। धिषे।
भरंत। विश्वे। बलिं। स्वः। नः। वि। त्वा। नरः। पुरुऽत्रा। सपर्यन्। पितुः। न। जिव्रेः। वि। वेदः। भरंत॥ साधुः।
न। गृध्नुः। अस्ताऽइव। शूरः। याताऽइव। भीमः। त्वेषः। समत्ऽसु॥ ३४॥ उप। प्र। जिन्वन्। उशतीः।
उशंतं। पतिं। न। नित्यं। जनयः। सऽनीळाः॥ स्वसारः। श्यावीं। अरुषीं। अजुष्रन्। चित्रं। उछंतीं।
उषसं। न। गावः॥ वीळु। चित्। दृळ्हा। पितरः। नः। उक्थैः। अद्रिं। रुजन्। अंगिरसः। रवेण। चक्रुः।
हृ दिवः। बृहतः। गातुं। अस्मे इति। अहः। स्वः। विविदुः। केतुं। उस्राः॥ दधन्। ऋतं। धनयन्। अस्य।
धीतिं। आत्। अर्यः। दिधिष्वः। विऽभृत्राः। अतृष्यंतीः। अपसः। यंति। अछ। देवान्। जन्म। प्रयसा। ६९
इत्

© Dharmartha Trust J&K. Digitized by eGangotri

वर्धयंतीः । मथीत् । यत् । ईं । विऽभ्रतः । मातरिश्वा । गृहेऽगृहे । श्येतः । जेन्यः । भूत् ।
आत् । ईं । राज्ञे । न । सहीयसे । सचा । सन् । आ । दूत्यं । भृगवाणः । विवाय । महे । य
त् । पित्रे । ईं । रसं । दिवे । कः । अव । सरत् । पृश्न्यः । चिकित्वान् । सृजत् । अस्ता । धृषता ।
दिद्युं । अस्मै । स्वायां । देवः । दुहितरि । त्विषिं । धात् ॥ १५ ॥ स्वे । आ । यः । तुभ्यं । दमे । आ ।
विभाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् । वर्धो इति । अग्ने । वयः । अस्य । द्विऽब
र्हाः । यासत् । राया । सऽरथं । यं । जुनासि । अग्निं । विश्वाः । अभि । पृक्षः । सचंते । समुद्रं ।
न । स्रवतः । सप्त । यह्वीः । न । जामिऽभिः । वि । चिकिते । वयः । नः । विदाः । देवेषु । प्रऽमतिं ।

© Dharmartha Trust J&K. Digitized by eGangotri

१०प्र

७० चिकित्वान्। आयन्। इषे। नृऽपतिं। तेजः। आनट्। शुचि। रेतः। निऽसिक्तं। द्यौः। अ
भीके। अग्निः। शर्धं। अनवद्यं। युवानं। सुऽआध्यं। जनयत्। सूदयत्। च। मनः।
न। यः। अध्वनः। सद्यः। एति। एकः। सत्रा। सूरः। वस्वः। ईशे। राजाना। मित्रावरुणा।
70 सुपाणी इति सुऽपाणी। गोषु। प्रियं। अमृतं। रक्षमाणा। मा। नः। अग्ने। सख्या।
पित्र्याणि। प्र। मर्षिष्ठाः। अभि। विदुः। कविः। सन्। नभः। न। रूपं। जरिमा। मिनाति।
पुरा। तस्याः। अभिऽशस्तेः। अधि। इहि। १६।। नि। काव्या। वेधसः। शश्वतः।
कः। हस्ते। दधानः। नर्या। पुरूणि। अग्निः। भुवत्। रयिऽपतिः। रयीणां। सत्रा। ७०

© Dharmartha Trust J&K. Digitized by eGangotri

तिस्रः । यत् । अग्ने ।

चक्राणः । अमृतानि । विश्वा । अस्मे इति । वत्सं । परि । संतं । न । विंदन् । इच्छंतः ।
विश्वे । अमृताः । अमूराः । श्रमऽयुवः । पदऽव्यः । धियंऽधाः । तस्थुः । पदे । परमे ।
चारु । अग्नेः । शरदः । त्वां । इत् । शुचिं । घृतेन । शुचयः । सपर्यान् । नामानि ।
चित् । दधिरे । यज्ञियानि । असूदयंत । तन्वः । सुऽजाताः । आ । रोदसी
इति । बृहती इति । वेविदानाः । प्र । रुद्रियाः । जभ्रिरे । यज्ञियासः । विदत् ।
मर्तः । नेमऽधिता । चिकित्वान् । अग्निं । पदे । परमे । तस्थिऽवांसं । संऽजा
नानाः । उप । सीदन् । अभिऽज्ञु । पत्नीऽवंतः । नमस्यं । नमस्यन्निति नमस

© Dharmartha Trust J&K. Digitized by eGangotri

७१ स्यन्। रिरिक्वांसः। तन्वः। कृण्वत। स्वाः। सखा। सख्युः। निऽमिषि। रक्षमाणाः॥ ५

त्रिः। सप्त। यत्। गुह्यानि। त्वे इति। इत्। पदा। अविदन्। निऽहिता। यज्ञियासः। ते

भिः। रक्षन्ते। अमृतं। सऽजोषाः। पशून्। च। स्थातॄन्। चरथं। च। पाहि। विद्वान्।

71 अग्ने। वयुनानि। क्षितीनां। वि। आ। अनुषक्। शुरुधः। जीवसे। धाः। अन्तःऽविद्वान्।

अध्वनः। देवऽयानान्। अतन्द्रः। दूतः। अभवः। हविःऽवाट्। सुऽआध्यः। दिवः। आ।

सप्त। यह्वीः। रायः। दुरः। वि। ऋतऽज्ञाः। अजानन्। विदत्। गव्यं। सरमा। दृळ्हं। ऊ

र्वं। येन। नु। कं। मानुषी। भोजते। विट्। आ। ये। विश्वा। सुऽअपत्यानि। तस्थुः।

© Dharmartha Trust J&K. Digitized by eGangotri

कृण्वानासः। अमृतऽत्वाय। गातुं। मन्हा। महत्ऽभिः। पृथिवी। वि। तस्थे।
माता। पुत्रैः। अदितिः। धायसे। वेरिति वेः। अधि। श्रियं। नि। दधुः। चारुं। अस्मि
नु। दिवः। यत्। अक्षी इति। अमृताः। अकृण्वन्। अध। क्षरंति। सिंधवः। न। सृष्टाः।
प्र। अनीचीः। अग्ने। अरुषीः। अजानन्॥ १८ ॥ रयिः। न। यः। पितृऽवित्तः। वयःऽ
धाः। सुऽप्रनीतिः। चिकितुषः। न। शासुः। स्योनऽशीः। अतिथिः। न। प्रीणानः।
होताऽइव। सद्म। विधतः। वि। तारीत्। देवः। न। यः। सविता। सत्यऽमन्मा। क्र
त्वा। निऽपाति। वृजनानि। विश्वा। पुरुऽप्रशस्तः। अमतिः। न। सत्यः। आत्माऽइव।

© Dharmartha Trust J&K. Digitized by eGangotri

शेवः । दिधिषाय्यः । भूत् । [illegible] । पृथिवीं । विश्वऽधायाः । उपऽक्षेति । हितऽमित्रः । न ।
[illegible]राजा । पुरःऽसदः । शर्मऽसदः । न । वीराः । अनवद्या । पतिजुष्टाऽइव । नारी । त्वं ।
त्वा । नरः । दमे । आ । नित्यं । इद्धं । अग्ने । सचंत । क्षितिषु । ध्रुवासु । अधि । द्युम्नं । नि ।
दधुः । भूरि । अस्मिन् । भव । विश्वऽआयुः । धरुणः । [illegible] रयीणां । वि । पृक्षः । अग्ने । मघऽ
वानः । अश्युः । वि । सूरयः । द दतः । विश्वं । आयुः । सनेम । वाजं । संऽइथेषु । अर्यः ।
भागं । देवेषु । श्रवसे । दधानाः ॥ ११ ॥ ऋतस्य । हि । धेनवः । वावशानाः । स्मत्ऽऊध्नीः ।
पीपयंत । द्युऽभक्ताः । पराऽवतः । सुऽमतिं । भिक्षमाणाः । वि । सिंधवः । समया । सस्रुः । ७२

© Dharmartha Trust J&K. Digitized by eGangotri

अद्रिं। त्वेइति। अग्ने। सुऽमतिं। भिक्षमाणाः। दिवि। श्रवः। दधिरे। यज्ञियासः। न
क्ता। च। चक्रुः। उषसा। विरूपेइति विऽरूपे। कृष्णं। च। वर्णं। अरुणं। च। सं। धुरिति
धुः। यान्। राये। मर्त्तान्। सुसूदः। अग्ने। ते। स्याम। मघऽवानः। वयं। च। छायाऽ
इव। विश्वं। भुवनं। सिसक्षि। आपप्रिवान्। रोदसीइति। अंतरिक्षं। अर्वत्ऽभिः।
अग्ने। अर्वतः। नृऽभिः। नॄन्। वीरैः। वीरान्। वनुयाम। त्वाऽऊताः। ईशानासः। पि
तृऽवित्तस्य। रायः। वि। सूरयः। शतऽहिमाः। नः। अश्युः। एता। ते। अग्ने। उचथानि।
वेधः। जुष्टानि। संतु। मनसे। हृदे। च। शकेम। रायः। सुऽधुरः। यमं। ते। अधि। श्रवः।

© Dharmartha Trust J&K. Digitized by eGangotri

प०अ० ७३ देवऽमर्त्तं । दधानाः ॥ २० ॥ उपऽप्रयन्तः । अध्वरं । मंत्रं । वोचेम । अग्नये । आरे । अस्मे इ
ति । च । शृण्वते । यः । स्नीहितीषु । पूर्व्यः । संऽजग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । ग
जंतवेः यं । उत । ब्रुवंतु । उत । अग्निः । वृत्रऽहा । अजनि । धनंऽजयः । रणेऽरणे । यस्य । दूतः । अ
73 सि । क्षये । वेषि । हव्यानि । वीतये । दस्मत् । कृणोषि । अध्वरं । तं । इत्था । सुऽहव्यं । अंगि
रः । सुऽदेवं । सहसः । यहो इति । जनाः । आहुः । सुऽबर्हिषं ॥ २१ ॥ आ । च । वहासि ।
तान् । इह । देवान् । उप । प्रऽशस्तये । हव्या । सुऽचंद्र । वीतये । नः । यो । उपऽब्दिः । अ
श्व्यः । शृण्वे । रथस्य । कत् । चन । यत् । अग्ने । यासि । दूत्यं । त्वाऽऊतः । वाजी । अह्नयः । ७३

© Dharmartha Trust J&K. Digitized by eGangotri

अभि । पूर्वस्मात् । अपरः । प्र । दाश्वान् । अग्ने । अस्थात् । उत । द्युऽमत् । सुऽवीर्यं । बृहत् ।
अग्ने । विवाससि । देवेभ्यः । देव । दाशुषे ॥ २२ ॥ जुषस्व । सप्रथःऽतमं । वचः । देवप्सरः
ऽतमं । हव्या । जुह्वानः । आसनि । अथा । ते । अंगिरःऽतम । अग्ने । वेधःऽतम । प्रियं ।
वोचेम । ब्रह्म । सानसि । कः । ते । जामिः । जनानां । अग्ने । कः । दाशुऽअध्वरः । कः ।
ह । कस्मिन् । असि । श्रितः । त्वं । जामिः । जनानां । अग्ने । मित्रः । असि । प्रियः । स
खा । सखिऽभ्यः । ईड्यः । यज । नः । मित्रावरुणा । यज । देवान् । ऋतं । बृहत् । अग्ने ।
यक्षि । स्वं । दमं ॥ २३ ॥ का । ते । उपऽइतिः । मनसः । वराय । भुवत् । अग्ने । शंऽ

© Dharmartha Trust J&K. Digitized by eGangotri

पु० प्र० ७४

74

तमा । का । मनीषा । कः । वा । यज्ञैः । परि । दक्षं । ते । आप । केन । वा । ते । मनसा । दाशे-
म । आ । इहि । अग्ने । इह । होता । नि । सीद । अदब्धः । सु । पुरःऽएता । भव । नः । अ-
वतां । त्वा । रोदसी इति । विश्वमिन्वे इति विश्वंऽइन्वे । यज । महे । सौमनसाय । देवा-
न् । प्र । सु । विश्वान् । रक्षसः । धक्षि । अग्ने । भव । यज्ञानां । अभिशस्तिऽपावा । अ-
थ । आ । वह । सोमऽपतिं । हरिऽभ्यां । आतिथ्यं । अस्मै । चकृम । सुऽदाव्ने । प्रजाऽ-
वता । वचसा । वह्निः । आसा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः । वेषि । होत्रं ।
उत । पोत्रं । यजत्र । बोधि । प्रऽयंतः । जनितः । वसूनां । यथा । विप्रस्य । मनुषः । ७४

© Dharmartha Trust J&K. Digitized by eGangotri

हविःऽभिः। देवान्। अयजः। कविऽभिः। कविः। सन्। एव। होतरिति। सत्यऽतर। त्वं। अ
द्य। अग्ने। मंद्रया। जुह्वा। यजस्व॥२५॥ कथा। दाशेम। अग्नये। का। अस्मै। देवऽजु
ष्टा। उच्यते। भामिने। गीः। यः। मर्त्येषु। अमृतः। ऋतऽवा। होता। यजिष्ठः। इत्। कृ
णोति। देवान्। यः। अध्वरेषु। शंऽतमः। ऋतऽवा। होता। तं। ऊं इति। नमःऽभिः। आ।
कृणुध्वं। अग्निः। यत्। वेः। मर्त्ताय। देवान्। सः। च। बोधाति। मनसा। यजाति। सः।
हि। क्रतुः। सः। मर्यः। सः। साधुः। मित्रः। न। भूत्। अद्भुतस्य। रथीः। तं। मेधेषु। प्रथ
मं। देवऽयंतीः। विशः। उप। ब्रुवते। दस्मं। आरीः। सः। नः। नृणां। नृऽतमः। रिशादाः।

© Dharmartha Trust J&K. Digitized by eGangotri

प०म० ७५ अग्निः । गिरः । अवसा । वेतु । धीतिं । तना । च । ये । मघऽवानः । शविष्ठाः । वाजऽप्रसूताः । इषं
यंत । मन्म । एव । अग्निः । गोतमेभिः । ऋतवा । विप्रेभिः । अस्तोष्ट । जातऽवेदाः । सः । एषु ।
द्युम्नं । पीपयत् । सः । वाजं । सः । पुष्टिं । याति । जोषं । आ । चिकित्वान् ॥ २५ ॥ अभि । त्वा ।
75 गोतमाः । गिरा । जातऽवेदः । विऽचर्षणे । द्युम्नैः । अभि । प्र । नोनुमः । तं । ऊं इति । त्वा ।
गोतमः । गिरा । रायःऽकामः । दुवस्यति । ० । वाजऽसातमं । अंगिरस्वत् । हवामहे । ० ।
वृत्रहन्ऽतमं । यः । दस्यून् । अवऽधूनुषे । ० । अवोचाम । रहूगणाः । अग्नये । मधुऽमत् ।
वचः । ० ॥ २६ ॥ हिरण्यऽकेशः । रजसः । विऽसारे । अहिः । धुनिः । वातःऽइव । ध्रजीमान् । ७५

© Dharmartha Trust J&K. Digitized by eGangotri

ई ३

शुचिऽभ्राजाः । उषसः । नवेदाः । यशस्वतीः । अपस्युवः । न । सत्याः । आ । ते । सुऽपर्णाः । अ
मिनंत । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदं । शिवाभिः । न । स्मयमानाभिः । आ । अ
गात् । पतंति । मिहः । स्तनयंति । अभ्रा । यत् । ऋतस्य । पयसा । पियानः । नयन् । ऋतस्य ।
पथिभिः । रजिष्ठैः । अर्यमा । मित्रः । वरुणः । परिऽज्मा । त्वचं । पृंचंति । उपरस्य । योनौ ।
अग्ने । वाजस्य । गोऽमतः । ईशानः । सहसः । यहो इति । अस्मे इति । धेहि । जातऽवेदः ।
महि । श्रवः । सः । इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा । रेवत् । अस्मभ्यं । पु
रुऽअनीक । दीदिहि । क्षपः । राजन् । उत । त्मना । अग्ने । वस्तोः । उत । उषसः । सः । तिग्म

© Dharmartha Trust J&K. Digitized by eGangotri

पं० प्र० ७६

ऽजंभैः। रक्षसः। दह। प्रति। २७। अव। नः। अग्ने। ऊतिऽभिः। गायत्रस्य। प्रऽभर्मणि।
विश्वासु। धीषु। वंद्य। आ। नः। अग्ने। रयिं। भर। सत्राऽसहं। वरेण्यं। विश्वासु। पृत्ऽसु।
दुस्तरं। ०। सुऽचेतुना। रयिं। विश्वऽआयुऽपोषसं। मार्डीकं। धेहि। जीवसे। प्र। पूताः।
तिग्मऽशोचिषे। वाचः। गोतम। अग्नये। भरस्व। सुम्नयुः। गिरः। यः। नः। अग्ने। अ
भिऽदासति। अंति। दूरे। पदीष्ट। सः। अस्माकं। इत्। वृधे। भव। सहस्रऽअक्षः। वि
चर्षणिः। अग्निः। रक्षांसि। सेधति। होता। गृणीते। उक्थ्यः। २८। इत्था। हि। सोमे।
इत्। मदे। ब्रह्मा। चकार। वर्धनं। शविष्ठ। वज्रिन्। ओजसा। पृथिव्याः। निः। शशाः। नि:।
७६

76

© Dharmartha Trust J&K. Digitized by eGangotri

अहिं । अर्चन् । अनु । स्वऽराज्यं ।। सः । त्वा । अमदत् । वृषा । मदः । सोमः । श्येनऽआभृतः ।
सुतः । येन । वृत्रं । निः । अत्ऽभ्यः । जघंथ । वज्रिन् । ओजसा ।। १ ।। प्र । इहि । अभि । इहि । इ
धृष्णुहि । न । ते । वज्रः । नि । यंसते । इंद्र । नृम्णं । हि । ते । शवः । हनः । वृत्रं । जयाः । अपः ।। ३ ।।
निः । इंद्र । भूम्याः । अधि । वृत्रं । जघंथ । निः । दिवः । सृज । मरुत्वतीः । अव । जीवऽधन्याः ।
इमाः । अपः ।। ४ ।। इंद्रः । वृत्रस्य । दोधतः । सानुं । वज्रेण । हीळितः । अभिऽक्रम्य । अव ।
जिघ्नते । अपः । सर्माय । चोदयन् ।। ५ ।। २९ ।। अधि । सानौ । नि । जिघ्नते । वज्रेण । श
तऽपर्वणा । मंदानः । इंद्रः । अंधसः । सखिऽभ्यः । गातुं । इच्छति ।। ६ ।। इंद्र । तुभ्यं । इत् ।

© Dharmartha Trust J&K. Digitized by eGangotri

अद्रिवः। अनु। त्वं। वज्रिन्। वीर्यं। यत्। ह। सं। मायिनं। मृगं। त्वं। कुं इति त्वं। मायया। अव
धीः ॥ ०॥ वि। ते। वज्रासः। अस्थिरन्। नवतिं। नाव्याः। अनु। महत्। ते। इंद्र। वीर्यं। वाह्वोः
ते। बलं। हितं ॥ ०॥ सहस्रं। साकं। अर्चत। परि। स्तोभत। विंशतिः। शता। एनं। अनु। अ
नोनवुः। इंद्राय। ब्रह्म। उत्ऽयतं ॥ ०॥ इंद्रः। वृत्रस्य। तविषीं। निः। अहन्। सहसा। स
हः। महत्। तत्। अस्य। पौंस्यं। वृत्रं। जघन्वान्। असृजत् ॥ ०॥ ३०॥ इमे इति। चित्।
तव। मन्यवे। वेपेते इति। भियसा। मही इति। यत्। इंद्र। वज्रिन्। ओजसा। वृत्रं।
मरुत्वान्। अवधीः ॥ ०॥ न। वेपसा। न। तन्यता। इंद्रं। वृत्रः। वि। बीभयत्। अभि। ७७

एनं । वज्रः । आयसः । सहस्रऽभृष्टिः ॥ आयत । ० । यत् । वृत्रं । तव । च । अशनिं । वज्रे
ण । सं ऽअयोधयः । अहिं । इंद्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । ० । अभिऽस्तने ।
ते । अद्रिऽवः । यत् । स्थाः । जगत् । च । रेजते । त्वष्टा । चित् । तव । मन्यवे । इंद्र । वेविज्य
ते । भिया । ० । नहि । नु । यात् । अधिऽइमसि । इंद्रं । कः । वीर्या । परः । तस्मिन् । नृ
म्णं । उत । क्रतुं । देवाः । ओजांसि । सं । दधुः । ० । यां । अथर्वा । मनुः । पिता । दध्यङ् ।
धियं । अत्नत । तस्मिन् । ब्रह्माणि । पूर्वऽथा । इंद्रे । उक्था । सं । अग्मत । ० । ३१ ।
इति प्रथमाष्टके पंचमोध्यायः ॥ ॥ ओं ॥ इंद्रो न वो पो षु षड्रुग सं तमघावति

© Dharmartha Trust J&K. Digitized by eGangotri

म
जागतं॑सा वि विंशतिः षळनुष्टुभमौष्णिहं पांक्तं गायत्रं त्रैष्टुभमास्त्वचाः प्रगाथः
प्र ये द्वादश मारुतं ह यं च म्यं ते त्रिष्टु मौ मरुतो दश गायत्रं प्रत्यक्षस सः षडा आगत
म मा विश्वं द्विरा धां से प्रस्तार पंक्तौ पंचमी विराड्रूपा नो दश वैश्वदेवं तु पंचा॰
घ घाः सप्तमी जगती सः षष्ठी विराडू स्थाना न सजुनीती नव गायत्रं मंत्यानुष्टुप्पूर्वं
78 सो म त्र्यधिका सोम्यं पंचम्या दि गायत्र्यो द्वादशोष्णिक् चैता उ त्या द्वनो वस्यं
च तु र्जगत्या दि षडुष्णिगं तेन्द्रे त्रीस आश्विनोग्नीषोमो द्वादशाग्नीषोमीयं
मा घा स्तिस्रो नुष्टुभं उ पांत्या स्तिस्रो गायत्र्यो ष्टमी जगती वेमं षोडशाकु ७९

© Dharmartha Trust J&K. Digitized by eGangotri

सआग्नेयंतद्धित्रिष्टुबंतंपूर्वेदेवास्त्रयःपादादेवास्तन्नोमित्रोद्वौचौलिंगोक्तदे
वतौयद्देवसंवासूक्तं॥६॥ ॥ॐ॥इंद्रः।मदाय।ववृधे।शवसे।वृत्रऽहा।नृऽ
भिः।तं।इत्।महत्ऽसु।आजिषु।उत।ईं।अर्भे।हवामहे।सः।वाजेषु।प्र।नः।अ
विषत्।असि।हि।वीर।सेन्यः।असि।भूरि।पराऽददिः।असि।दभ्रस्य।चि
त्।वृधः।यजमानाय।शिक्षसि।सुन्वते।भूरि।ते।वसु।यत्।उत्ऽईरते।आज
यः।धृष्णवे।धीयते।धना।युक्ष्वा।मदऽच्युता।हरीइति।कं।हनः।कं।वसौ।दधः।अ
स्मान्।इंद्र।वसौ।दधः।क्रत्वा।महान्।अनुऽस्वधं।भीमः।आ।ववृधे।शवः।श्रि

© Dharmartha Trust J&K. Digitized by eGangotri

प०प्र०
७१

79

ये। सख्यः। उपाकयोः। नि। शिप्री। हरिऽवान्। दधे। हस्तयोः। वज्रं। आयसं। आ।
पप्रौ। पार्थिवं। रजः। बद्बधे। रोचना। दिवि। न। त्वाऽवान्। [illegible] इंद्रा।
कः। चन। आ। न। आ। ततः। न। जनिष्यते। अति। विश्वं। ववक्षिथ॥१॥ यः। अर्यः। मर्तऽ।
भोजनं। पराऽददाति। दाशुषे। इंद्रः। अस्मभ्यं। शिक्षतु। वि। भज। भूरि। ते। व
सु। भक्षीय। तव। राधसः। मदेऽमदे। हि। नः। ददिः। यूथा। गवां। ऋजुऽक्रतुः। सं।
गृभाय। पुरु। शता। उभया। हस्त्या। वसु। शिशीहि। रायः। आ। भर। मादयस्व। सुते।
सचा। शवसे। शूर। राधसे। विद्म। हि। त्वा। पुरुऽवसुं। उप। कामान्। ससृज्महे।

७९

© Dharmartha Trust J&K. Digitized by eGangotri

अध। नः। अविना। भव। एते। ते। इंद्र। जंतवः। विश्वं। पुष्यंति। वार्यं। अंतः। हि। ख्यः।
जनानां। अर्यः। वेदः। अदाशुषां। तेषां। नः। वेदः। आ। भर॥२॥ उपोइति। सु। श्र
णुहि। गिरः। मघऽवन्। मा। अतथाःऽइव। यदा। नः। सूनृताऽवतः। करः। आत्।
अर्थयासे। इत्। योज। नु। इंद्र। ते। हरीइति। अक्षन्। अमीमदंत। हि। अव। प्रि
याः। अधूषत। अस्तोषत। स्वऽभानवः। विप्राः। नविष्ठया। मती॰। सुऽसंदृशं।
त्वा। वयं। मघऽवन्। वंदिषीमहि। प्र। नूनं। पूर्णऽवंधुरः। स्तुतः। याहि। वशान्।
अनु॥१०॥ सः। घ। तं। वृषणं। रथं। अधि। तिष्ठाति। गोऽविदं। यः। पात्रं। हारिऽयो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ ८० उनं। पूर्णं। इंद्र। चिकेतति॥०॥ युक्तः। ते। अस्तु। दक्षिणः। उत। सव्यः। शतक्रतो इति
शतऽक्रतो। तेन। जायां। उप। प्रियां। मंदानः। याहि। अंधसः॥०॥ युनज्मि। ते। ब्रह्मणा।
केशिना। हरी इति। उप। प्र। याहि। दधिषे। गभस्त्योः। उत्। त्वा। सुतासः। रभसाः।
80 अमंदिषुः। पूषण्ऽवान्। वज्रिन्। सं। ऊं इति। पत्न्या। अमदः॥ २॥ अश्वऽवति।
प्रथमः। गोषु। गच्छति। सुप्रऽअवीः। इंद्र। मर्त्यः। तव। ऊतिऽभिः। तं। इत्। पृणक्षि।
वसुना। भवीयसा। सिंधुं। आपः। यथा। अभितः। विऽचेतसः। आपः। न। देवीः।
उप। यंति। होत्रियं। अवः। पश्यंति। विऽततं। यथा। रजः। प्राचैः। देवासः। प्रनयं ८०

© Dharmartha Trust J&K. Digitized by eGangotri

ति। देवऽयुं। ब्रह्मऽप्रियं। जोषयंते। वराःऽइव। अधि। द्यवोः। अदधाः। उक्थ्यं। वचः।
यत्ऽस्रुचा। मिथुना। या। सपर्यतः। असंऽयत्तः। व्रते। ते। पुष्यति। भद्रा। शक्तिः। क्षेति
यजमानाय। सुन्वते। आत्। अंगिराः। प्रथमं। दधिरे। वयः। इद्धऽअग्नयः। शम्या।
ये। सुऽकृत्यया। सर्वं। पणेः। सं। अविंदंत। भोजनं। अश्वऽवंतं। गोऽमंतं। आ। प
शुं। नरः। यज्ञैः। अथर्वा। प्रथमः। पथः। तते। ततः। सूर्यः। व्रतऽपाः। वेनः।
आ। अजनि। आ। गाः। आजत्। उशना। काव्यः। सचा। यमस्य। जातं। अमृ
तं। यजामहे। बर्हिः। वा। यत्। सुऽअपत्याय। वृज्यते। अर्कः। वा। श्लोकं। आऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प्र०प०६ घोषते। दिवि। ग्रावा। यत्र। वदति। कारुः। उक्थ्यः। तस्य। इत्। उ। इंद्रः। अभि। पित्वे

८२ सुऽरण्यति॥४॥ असौ। वि। सोमः। इंद्र। ते। शविष्ठ। धृष्णो। इति। आ। गहि। आ।

त्वा। पृणक्तु। इंद्रियं। रजः। सूर्यः। न। रश्मिऽभिः। इंद्रं। इत्। हरी इति। वहतः।

अप्रतिऽधृष्टऽशवसं। ऋषीणां। च। स्तुतीः। उप। यज्ञं। च। मानुषाणां। आ। तिष्ठ। वृत्र

हन्। रथं। युक्ता। ते। ब्रह्मणा। हरी इति। अर्वाचीनं। सु। ते। मनः। ग्रावा। कृणोतु।

वग्नुना। इमं। इंद्र। सुतं। पिब। ज्येष्ठं। अमर्त्यं। मदं। शुक्रस्य। त्वा। अभि। अक्षरन्। धाराः। अभि।

ऋतस्य। सदने। इंद्राय। नूनं। अर्चत। उक्थानि। च। ब्रवीतन। सुताः। अमत्सुः। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

यत्नू।

इंद्र्वः। ज्येष्ठं। नुमस्युत्। सहः॥ ५॥ नकिः। त्वत्। रथिऽतरः। हरीइति। इंद्र। यच्छसे। नकिः। त्वा। अनु। मज्मना। नकिः। सुऽअश्वः। आनुशे। यः। एकः। इत्। विऽदयते। वसु। मर्त्याय। दाशुषे। ईशानः। अप्रतिऽस्कुतः। इंद्रः। अंग। कुदा। मर्त्तः। अराधसं। पदा। क्षुंपंऽइव। स्फुरत्। कुदा। नः। शुश्रवत्। गिरः। इंद्रः। अंग। यः। चित्। हि। त्वा। बहुऽभ्यः। आ। सुतऽवान्। आऽविवासति। उग्रं। तत्। पत्यते। शवः। इंद्रः। अंग। स्वादोः। इत्था। विषुऽवतः। मध्वः। पिबंति। गौर्यः। याः। इंद्रेण। सऽयावरीः। रष्णा। मदंति। शोभसे। वस्वीः। अनु। स्वऽराज्यं॥ ७॥ ताः। अस्य। पृ

© Dharmartha Trust J&K. Digitized by eGangotri

म.प. शनाऽयुवः। सोमं। श्रीणंति। पृश्नयः। प्रियाः। इंद्रस्य। धेनवः। वज्रं। हिन्वंति। सायकं।०
८२ ताः। अस्य। नमसा। सहः। सपर्यंति। प्रऽचेतसः। व्रतानि। अस्य। सश्चिरे। पुरूणि। पू
र्वऽचित्तये।०इंद्रः। दधीचः। अस्थऽभिः। वृत्राणि। अप्रतिऽस्कुतः। जघान। नवतीः। न
४२ व। इच्छन्। अश्वस्य। यत्। शिरः। पर्वतेषु। अपऽश्रितं। तत्। विदत्। शर्यणाऽवति। अत्र।
अह। गोः। अमन्वत। नाम। त्वष्टुः। अपीच्यं। इत्था। चंद्रमसः। गृहे॥७॥ कः। अद्य। युंक्ते।
धुरि। गाः। ऋतस्य। शिमीऽवतः। भामिनः। दुःऽहृणायून्। आसन्ऽइषून्। हृत्सुऽअ
सः। मयःऽभून्। यः। एषां। भृसां। ऋणधत्। सः। जीवात्। कः। ईषते। तुज्यते। कः। बिभाय। ८२

© Dharmartha Trust J&K. Digitized by eGangotri

कः। मंसते। संतं। इंद्रं। कः। अंति। कः। तोकाय। कः। इभाय। उत। राये। अधि। ब्रवत्। तन्वे। कः।
जनाय। कः। अग्निं। ईट्टे। हविषा। घृतेन। स्रुचा। यजाते। ऋतुऽभिः। ध्रुवेभिः। कस्मै। देवाः।
आ। वहान्। आशु। होम। कः। मंसते। वीतिऽहोत्रः। सुऽदेवः। त्वं। अंग। प्र। शंसिषः। देवः। श
विष्ठ। मर्त्यं। न। त्वत्। अन्यः। मघऽवन्। अस्ति। मर्डिता। इंद्र। ब्रवीमि। ते। वचः। मा। ते। राधां
सि। मा। ते। ऊतयः। वसो इति। अस्मान्। कदा। चन। दभन्। विश्वा। च। नः। उपऽमिमीहि।
मानुष। वसूनि। चर्षणिऽभ्यः। आ॥ २। प्र। ये। शुंभंते। जनयः। न। सप्तयः। यामन्। रुद्रस्य।
सूनवः। सुऽदंससः। रोदसी इति। हि। मरुतः। चक्रिरे। वृधे। मदंति। वीराः। विदथेषु। घृष्वयः।

© Dharmartha Trust J&K. Digitized by eGangotri

प्र॰१॰ तोउक्षितासः।महिमानं।आशत।दिवि।रुद्रासः।अधि।चक्रिरे।सदः।अर्चंतः।अर्कं।जनयंतः
८३ ।इंद्रियं।अधि।श्रियः।दधिरे।पृश्निऽमातरः।गोऽमातरः।यत्।शुभयंते।अंजिऽभिः।तनूषु।
शुभ्राः।दधिरे।विरुक्मतः।बाधंते।विश्वं।अभिऽमातिनं।अप।वर्त्मानि।एषां।अनु।रीय
83 ते।घृतं।विद्ये।भ्राजंते।सुऽमखासः।ऋष्टिऽभिः।प्रऽच्यवयंतः।अच्युता।चित्।ओजसा।
मनःऽजुवः।यत्।मरुतः।रथेषु।आ।वृषऽव्रातासः।पृषतीः।अयुग्ध्वं।प्र।यत्।रथेषु।पृषतीः।ग्
।अयुग्ध्वं।वाजे।अद्रिं।मरुतः।रंहयंतः।उत।अरुषस्य।वि।स्यंति।धाराः।चर्मऽइव।उदऽ
भिः।वि।उंदंति।भूम।आ।वः।वहंतु।सप्तयः।रघुऽस्यदः।रघुऽपत्वानः।प्र।जिगात।बाहु ८३

© Dharmartha Trust J&K. Digitized by eGangotri

ऽभिः। सीदत। आ। बर्हिः। उरु। वः। सदः। कृतं। मादयध्वं। मरुतः। मध्वः। अंधसः॥ ६॥ ते।
अवर्धंत। स्वऽतवसः। महिऽत्वना। आ। नाकं। तस्थुः। उरु। चक्रिरे। सदः। विष्णुः। य
त्। ह। आवत्। वृषणं। मदऽच्युतं। वयः। न। सीदन्। अधि। बर्हिषि। प्रिये॥ शूराःऽइव। इ
त्। युयुधयः। न। जग्मयः। श्रवस्यवः। न। पृतनासु। येतिरे। भयंते। विश्वा। भुवना। म
रुत्ऽभ्यः। राजानःऽइव। त्वेषऽसंदृशः। नरः॥ त्वष्टा। यत्। वज्रं। सुऽकृतं। हिरण्ययं। सह
स्रऽभृष्टिं। सुऽअपाः। अवर्तयत्। धत्ते। इंद्रः। नरि। अपांसि। कर्तवे। अहन्। वृत्रं। निः। अ
पां। औब्जत्। अर्णवं। ऊर्ध्वं। नुनुद्रे। अवतं। ते। ओजसा। दादृहाणं। चित्। बिभिदुः। वि

© Dharmartha Trust J&K. Digitized by eGangotri

प्र·५· पर्वतं। धमंतः। वाणं। मरुतः। सुऽदानवः। मदे। सोमस्य। रण्यानि। चक्रिरे। जिह्मं। नुनु
८४ द्रे। अवतं। तया। दिशा। असिंचन्। उत्सं। गोतमाय। तृष्णऽजे। आ। गच्छंति। ईं। अवसा।
चित्रऽभानवः। कामं। विप्रस्य। तर्पयंत। धामऽभिः। या। वः। शशमानाय। संति। त्रिऽ शर्म
धातूनि। दाशुषे। यच्छत। अधि। अस्मभ्यं। तानि। मरुतः। वि। यंत। रयिं। नः। धत्त। वृष
णः। सुऽवीरं। १०। मरुतः। यस्य। हि। क्षये। पाथ। दिवः। विऽमहसः। सः। सुऽगोपातमः
। जनः। यज्ञैः। वा। यज्ञऽवाहसः। विप्रस्य। वा। मतीनां। मरुतः। शृणुत। हवं। उत। वा। यस्य।
वा। जिनः। अनु। विप्रं। अतक्षत। सः। गंता। गोऽमति। व्रजे। अस्य। वीरस्य। बर्हिषि। सुतः। ८४

84

© Dharmartha Trust J&K. Digitized by eGangotri

सोमः। दिविष्टिषु। उक्थं। मदः। च। शस्यते। अस्य। श्रोषंतु। आ। भुवः। विश्वाः। यः। च
र्षणीः। अभि। सूरं। चित्। सस्रुषीः। इषः॥३३॥ पूर्वीभिः। हि। ददाशिम। शरत्ऽ
भिः। मरुतः। वयं। अवःऽभिः। चर्षणीनां। सुऽभगः। सः। प्रऽयज्यवः। मरुतः। अ
स्तु। मर्त्यः। यस्य। प्रयांसि। पर्षथ। शशमानस्य। वा। नरः। स्वेदस्य। सत्यऽशवसः।
विद। कामस्य। वेनतः। यूयं। तत्। सत्यऽशवसः। आविः। कर्त। महिऽत्वना। विध्यत।
विऽद्युता। रक्षः। गूहत। गुह्यं। तमः। वि। यात। विश्वं। अत्रिणं। ज्योतिः। कर्त। यत्।
उश्मसि॥ऽ२॥ प्रऽत्वक्षसः। प्रऽतवसः। विऽरप्शिनः। अनानताः। अविथुराः। ऋजी

© Dharmartha Trust J&K. Digitized by eGangotri

ऋ.प. षिणः। जुष्टऽतमासः। नृऽतमासः। अंजिऽभिः। वि। आनज्रे। के। चित्। उस्राःऽइव। स्तृऽ
८५ भिः। उपऽह्वरेषु। यत्। अचिध्वं। ययिं। वयःऽइव। मरुतः। केन। चित्। पथा। श्चोतंति।
85 कोशाः। उप। वः। रथेषु। आ। घृतं। उक्षत। मधुऽवर्णं। अर्चते। प्र। एषां। अज्मेषु। विथुरा
ऽइव। रेजते। भूमिः। यामेषु। यत्। ह। युंजते। शुभे। ते। क्रीळयः। धुनयः। भ्राजत्ऽऋष्टयः
। स्वयं। महिऽत्वं। पनयंत। धूतयः। सः। हि। स्वऽसृत्। पृषत्ऽअश्वः। युवा। गणः। अया।
ईशानः। तविषीभिः। आऽवृतः। असि। सत्यः। ऋणऽयावा। अनेद्यः। अस्याः। धियः। प्रऽअ
विता। अथ। वृषा। गणः। पितुः। प्रत्नस्य। जन्मना। वदामसि। सोमस्य। जिह्वा। प्र। जिगाति। ८५

© Dharmartha Trust J&K. Digitized by eGangotri

वक्षसा । यत्र । ईं । इन्द्रं । शमि । ऋक्वाणः । आशत । आत् । इत् । नामानि । यज्ञियानि । दधिरे ।
श्रियसे । कं । भानुऽभिः । सं । मिमिक्षिरे । ते । रश्मिऽभिः । ते । ऋक्वऽभिः । सुऽखादयः । ते । वा
शीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥ ३३ ॥ आ । विद्युन्मत्ऽ
भिः । मरुतः । सुऽअर्कैः । रथेभिः । यात । ऋष्टिमत्ऽभिः । अश्वऽपर्णैः । आ । वर्षिष्ठया । नः ।
इषा । वयः । न । पप्तत । सुऽमायाः । ते । अरुणेभिः । वरं । आ । पिशंगैः । शुभे । कं । यान्ति । रथतूः
ऽभिः । अश्वैः । रुक्मः । न । चित्रः । स्वधितिऽवान् । पव्या । रथस्य । जंघनंत । भूम । श्रिये । कं ।
वः । अधि । तनूषु । वाशीः । मेधा । वना । न । कृणवंते । ऊर्ध्वा । युष्मभ्यं । कं । मरुतः । सुऽजाताः ।

© Dharmartha Trust J&K. Digitized by eGangotri

ग्र·प· तुविऽद्युम्नासः। धनयन्त। अद्रिं। अहानि। गृध्राः। परि। आ। वः। आ। अगुः। इमां। धियं। वार्का
८६ र्यां। च। देवीं। ब्रह्म। कृण्वन्तः। गोतमासः। अर्कैः। ऊर्ध्वं। नुनुद्रे। उत्सऽधिं। पिबध्यै। एतत्। त्य
त्। न। योजनं। अचेति। सस्वः। ह। यत्। मरुतः। गोतमः। वः। पश्यन्। हिरण्यऽचक्रान्। अ
86 यःऽदंष्ट्रान्। विऽधावतः। वराहून्। एषा। स्या। वः। मरुतः। अनुऽभर्त्री। प्रति। स्तोभति। वाघ
तः। न। वाणी। अस्तोभयत्। वृथा। आसां। अनु। स्वधां। गभस्त्योः॥१४॥ आ। नः। भद्राः।
क्रतवः। यन्तु। विश्वतः। अदब्धासः। अपरिऽइतासः। उत्ऽभिदः। देवाः। नः। यथा। सदं। इ
त्। वृधे। असन्। अप्रऽआयुवः। रक्षितारः। दिवेऽदिवे। देवानां। भद्रा। सुऽमतिः। ऋजुऽ ८६

© Dharmartha Trust J&K. Digitized by eGangotri

यतां।देवानां।रातिः।अभि।नः।नि।वर्ततां।देवानां।सख्यं।उप।सेदिम।वयं।देवाः।नः।
आयुः।प्र।तिरंतु।जीवसे।तान्।पूर्वया।निऽविदा।हूमहे।वयं।भगं।मित्रं।अदितिं।द
क्षं।अस्रिधं।अर्यमणं।वरुणं।सोमं।अश्विना।सरस्वती।नः।सुऽभगा।मयः।करत्।
तत्।नः।वातः।मयःऽभु।वातु।भेषजं।तत्।माता।पृथिवी।तत्।पिता।द्यौः।तत्।ग्रावाणः।
सोमऽसुतः।मयःऽभुवः।तत्।अश्विना।शृणुतं।धिष्ण्या।युवं।तं।ईशानं।जगतः।तस्थु
षः।पतिं।धियंऽ जिन्वं।अवसे।हूमहे।वयं।पूषा।नः।यथा।वेदसां।असत्।वृधे।रक्षि
ता।पायुः।अदब्धः।स्वस्तये।।१५।।स्वस्ति।नः।इंद्रः।वृद्धऽश्रवाः।स्वस्ति।नः।पूषा।विश्वऽ

© Dharmartha Trust J&K. Digitized by eGangotri

ग्र·प· वेदाः। स्वस्ति। नः। तार्क्ष्यः। अरिष्टऽनेमिः। स्वस्ति। नः। बृहस्पतिः। दधातु। पृषत्ऽअ
८७ श्वाः। मरुतः। पृश्निऽमातरः। शुभंऽयावानः। विदथेषु। जग्मयः। अग्निऽजिह्वाः। म
नवः। सूरऽचक्षसः। विश्वे। नः। देवाः। अवसा। आ। गमन्। इह। भद्रं। कर्णेभिः। शृणु
87 याम। देवाः। भद्रं। पश्येम। अक्षऽभिः। यजत्राः। स्थिरैः। अंगैः। तुस्तुऽवांसः। तनूभिः।
वि। अशेम। देवऽहितं। यत्। आयुः। शतं। इत्। नु। शरदः। अंति। देवाः। यत्र। नः। चक्र। जर
त सं। तनूनां। पुत्रासः। यत्र। पितरः। भवंति। मा। नः। मध्या। रीरिषत। आयुः। गंतोः। अदितिः
। द्यौः। अदितिः। अंतरिक्षं। अदितिः। माता। सः। पिता। सः। पुत्रः। विश्वे। देवाः। अदितिः। ८७

© Dharmartha Trust J&K. Digitized by eGangotri

पंच। जनाः। अदितिः। जातं। आदितिः। जनिऽत्वं॥ १६॥ ऋजुऽनीती। नः। वरुणः। मित्रः। नय
तु। विद्वान्। अर्यमा। देवैः। सजोषाः। ते। हि। वस्वः। वसवानाः। ते। अप्रऽमूराः। महःऽभिः।
व्रता। रक्षंते। विश्वाहा। ते। अस्मभ्यं। शर्म। यंसन्। अमृताः। मर्त्येभ्यः। बाधमानाः। अ
प। द्विषः। वि। नः। पथः। सुविताय। चियंतु। इंद्रः। मरुतः। पूषा। भगः। वंद्यासः। उत। नः।
धियः। गोऽअग्राः। पूषन्। विष्णो इति। एवऽयावः। कर्त्त। नः। स्वस्तिऽमतः॥ १७॥ मधु।
वाताः। ऋतऽयते। मधु। क्षरंति। सिंधवः। माध्वीः। नः। संतु। ओषधीः। मधु। नक्तं। उत। उ
षसः। मधुऽमत्। पार्थिवं। रजः। मधु। द्यौः। अस्तु। नः। पिता। मधुऽमान्। नः। वनस्पतिः।

© Dharmartha Trust J&K. Digitized by eGangotri

ऋ॰प॰ मधु॑ऽमान्। अस्तु। सूर्यः। माध्वीः। गावः। भवंतु। नः। शं। नः। मित्रः। शं। वरुणः। शं। नः। भवतु। अ

९८ अर्यमा। शं। नः। इंद्रः। बृहस्पतिः। शं। नः। विष्णुः। उरुऽक्रमः। ॥९०॥ त्वं। सोम। प्र। चिकितः। म

नीषा। त्वं। रजिष्ठं। अनु। नेषि। पंथां। तव। प्रऽनीती। पितरः। नः। इंदो इति। देवेषु। रत्नं। अभ

४४ जंत। धीराः। त्वं। सोम। क्रतुऽभिः। सुऽक्रतुः। भूः। त्वं। दक्षैः। सुऽदक्षः। विश्वऽवेदाः। त्वं। वृषा।

वृषऽत्वेभिः। महिऽत्वा। द्युम्नेभिः। द्युम्नी। अभवः। नृऽचक्षाः। राज्ञः। नु। ते। वरुणस्य। व्रता

नि। बृहत्। गभीरं। तव। सोम। धाम। शुचिः। त्वं। असि। प्रियः। न। मित्रः। दक्षाय्यः। अर्य

माऽइव। असि। सोम। या। ते। धामा। दिवि। या। पृथिव्यां। या। पर्वतेषु। ओषधीषु। अप्ऽसु। ९८

नि।

© Dharmartha Trust J&K. Digitized by eGangotri

तेभिः। नः। विश्वैः। सुऽमनाः। अहेळन्। राजन्। सोम। प्रति। हव्या। गृभाय। त्वं। सोम। असि। स
त्ऽपतिः। त्वं। राजा। उत। वृत्रऽहा। त्वं। भद्रः। असि। क्रतुः॥१९॥ त्वं। च। सोम। नः। वशः। जीवातुं।
न। मरामहे। प्रियऽस्तोत्रः। वनस्पतिः। त्वं। सोम। महे। भगं। त्वं। यूने। ऋतऽयते। दक्षं। दधासि।
जीवसे। त्वं। नः। सोम। विश्वतः। रक्ष। राजन्। अघऽयतः। न। रिष्येत्। त्वाऽवतः। सखा। सोम। याः।
ते। मयःऽभुवः। ऊतयः। सन्ति। दाशुषे। ताभिः। नः। अविता। भव। इमं। यज्ञं। इदं। वचः। जुजुषाणः।
उपऽआगहि। सोम। त्वं। नः। वृधे। भव॥२०॥ सोम। गीःऽभिः। त्वा। वयं। वर्द्धयामः। वचःऽविदः।
सुऽमृळीकः। नः। आ। विश। गयऽस्फानः। अमीवऽहा। वसुऽवित्। पुष्टिऽवर्द्धनः। सुऽमित्रः। सो

© Dharmartha Trust J&K. Digitized by eGangotri

म.प. मु।नः।भव।सोम।ररंधि।नः।हृदि।गावः।न।यवसेषु।आ।मर्यःऽइव।स्वे।ओक्ये।यः।सोम।
८९ सख्ये।तव।ररणत्।देव।मर्त्यः।तं।दक्षः।सचते।कविः।उरुष्य।नः।अभिऽशस्तेः।सोम।नि।
89 पाहि।अंहसः।सखा।सुऽशेवः।एधि।नः॥२१॥आ।प्यायस्व।सं।एतु।ते।विश्वतः।सोम।
न वृष्ण्यं।भव।वाजस्य।संऽगथे।आ।प्यायस्व।मदिंऽतम।सोम।विश्वेभिः।अंशुऽभिः।भव।
नः।सुश्रवःऽतमः।सखा।वृधे।सं।ते।पयांसि।सं।ऊंइति।यंतु।वाजाः।सं।वृष्ण्यानि।अभि
मातिऽसहः।आऽप्यायमानः।अमृताय।सोम।दिवि।श्रवांसि।उत्ऽतमानि।धिष्व।०हवि
षा।यजंति।ता।ते।विश्वा।परिऽभूः।अस्तु।यज्ञं।गयऽस्फानः।प्रऽतरणः।सुऽवीरः।अवीरऽ ८९

© Dharmartha Trust J&K. Digitized by eGangotri

हा। प्र। चर। सोम। दुर्यान्। सोमः। धेनुं। सोमः। अर्वन्तं। आशुं। सोमः। वीरं। कर्मण्यं। ददाति। स
दन्यं। विदथ्यं। सभेयं। पितृऽश्रवणं। यः। ददाशत्। अस्मै॥ २०॥ अषाळ्हं। युत्ऽसु। पृतनासु।
पप्रिं। स्वःऽसां। अप्सां। वृजनस्य। गोपां। भरेषुऽजां। सुऽक्षितिं। सुऽश्रवसं। जयन्तं। त्वां। अ
नु। मदेम। सोम। त्वं। इमाः। ओषधीः। सोम। विश्वाः। त्वं। अपः। अजनयः। त्वं। गाः। त्वं। आ। त
तन्थ। उरु। अन्तरिक्षं। त्वं। ज्योतिषा। वि। तमः। ववर्थ। देवेन। नः। मनसा। देव। सोम। रायः। भा
गं। सहसाऽवन्। अभि। युध्य। मा। त्वा। आ। तनत्। ईशिषे। वीर्यस्य। उभयेभ्यः। प्र। चिकित्सा
गोऽइष्टौ॥ २३॥ एताः। ऊं इति। त्याः। उषसः। केतुं। अक्रत। पूर्वे। अर्धे। रजसः। भानुं। अंजते।

© Dharmartha Trust J&K. Digitized by eGangotri

प्र.प. निःऽकृण्वानाः। आयुधानिऽइव। धृष्णवः। प्रति। गावः। अरुषीः। यंति। मातरः॥ उत्। अप
९० प्तन्। अरुणाः। भानवः। वृथा। सुऽआयुजः। अरुषीः। गाः। अयुक्षत। अक्रन्। उषसः। व
युनानि। पूर्वऽथा। रुशंतं। भानुं। अरुषीः। अशिश्रयुः॥ अर्चंति। नारीः। अपसः। न। विष्टिऽ
90 भिः। समानेन। योजनेन। आ। पराऽवतः। इषं। वहंतीः। सुऽकृते। सुऽदानवे। विश्वा। इत्।
अह। यजमानाय। सुन्वते॥ अधि। पेशांसि। वपते। नृतूःऽइव। अप। ऊर्णुते। वक्षः। उस्राऽइ
व। बर्जहं। ज्योतिः। विश्वस्मै। भुवनाय। कृण्वती। गावः। न। व्रजं। वि। उषाः। आवरित्यावः। त
मः॥ प्रति। अर्चिः। रुशत्। अस्याः। अदर्शि। वि। तिष्ठते। बाधते। कृष्णं। अभ्वं। स्वरुं। न। पेशः। ९०

© Dharmartha Trust J&K. Digitized by eGangotri

विदथेषु। अंजन्। चित्रं। दिवः। दुहिता। भानुं। अश्रेत्॥ २४॥ अतारिष्म। तमसः। पारं। अस्य।
उषाः। उच्छंती। वयुना। कृणोति। श्रिये। छंदः। न। स्मयते। विभाती। सुऽप्रतीका। सौमन
साय। अजीगरिति। भास्वती। नेत्री। सूनृतानां। अचेति। दिवः। स्तवे। दुहिता। गोतमे
भिः। प्रजाऽवतः। नृऽवतः। अश्वऽबुध्यान्। उषः। गोऽअग्रान्। उप। मासि। वाजान्। उषः।
तं। अश्यां। यशसं। सुऽवीरं। दासऽप्रवर्गं। रयिं। अश्वऽबुध्यं। सुऽदंससा। श्रवसा। या। सं
विऽभासि। वाजऽप्रसूता। सुऽभगे। बृहंतं। विश्वानि। देवी। भुवना। अभिऽचक्ष्य। प्र
तीची। चक्षुः। उर्विया। वि। भाति। विश्वं। जीवं। चरसे। बोधयंती। विश्वस्य। वाचं। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प्र.प. विऽरत्। मनायोः। पुनःऽपुनः। जायमाना। पुराणी। समानं। वर्णं। अभि। शुंभमाना।।

९१ श्वघ्नीऽइव। कृत्नुः। विजः। आऽमिनाना। मर्त्तस्य। देवी। जरयंती। आयुः।।२८।।

विऽऊर्ण्वती। दिवः। अंतान्। अबोधि। अप। स्वसारं। सनुतः। युयोति। प्रऽमिन

ती। मनुष्या। युगानि। योषा। जारस्य। चक्षसा। वि। भाति। पशून्। न। चित्रा। सु

ऽभगा। प्रथाना। सिंधुः। न। क्षोदः। उर्विया। वि। अश्वैत्। आऽमिनती। दैव्यानि। व्रता

नि। सूर्यस्य। चेति। रश्मिऽभिः। दृशाना। उषः। तत्। चित्रं। आ। भर। अस्मभ्यं। वाजि

नीऽवति। येन। तोकं। च। तनयं। च। धामहे। उषः। अद्य। इह। गोऽमति। अश्वऽवति। वि ९१

91

© Dharmartha Trust J&K. Digitized by eGangotri

माऽवत्। रिरेवत्। अस्मे इति। वि। उच्छ। सूनृताऽवति। युक्ष्व। हि। वाजिनीऽवति। अश्वान्
। अद्य। अरुणान्। उषः। अथ। नः। विश्वा। सौभगानि। आ। वह॥ २६॥ अश्विना। वर्तिः।
अस्मत्। आ। गोऽमत्। दस्रा। हिरण्यऽवत्। अर्वाक्। रथं। सऽमनसा। नि। यच्छतं।
यौ। इत्था। श्लोकं। आ। दिवः। ज्योतिः। जनाय। चक्रथुः। आ। नः। ऊर्जं। वहतं। अश्वि
ना। युवं। आ। इह। देवा। मयःऽभुवा। दस्रा। हिरण्यवर्त्तनी इति हिरण्यऽवर्त्तनी। उषःऽ
बुधः। वहंतु। सोमऽपीतये॥ २७॥ अग्नीषोमौ। इमं। सु। मे। शृणुतं। वृषणा। हवं। प्रति।
सुऽउक्तानि। हर्यतं। भवतं। दाशुषे। मयः। अग्नीषोमा। यः। अद्य। वां। इदं। वचः। सपर्य

© Dharmartha Trust J&K. Digitized by eGangotri

ऋ.प. ति। तस्मै। धत्तं। सुऽवीर्यं। गवां। पोषं। सुऽअश्व्यं। अग्नीषोमा। यः। आऽहुतिं। यः। वां। दाशात्।
९२ हविःऽकृतिं। सः। प्रऽजया। सुऽवीर्यं। विश्वं। आयुः। वि। अश्नवत्। अग्नीषोमा। चेति। तत्।
वीर्यं। वां। यत्। अमुष्णीतं। अवसं। पणिं। गाः। अव। अतिरतं। बृसयस्य। शेषः। अविंदतं।
92 ज्योतिः। एकं। बहुऽभ्यः। युवं। एतानि। दिवि। रोचनानि। अग्निः। च। सोम। सक्रतू इति सऽ
क्रतू। अधत्तं। युवं। सिंधून्। अभिऽशस्तेः। अवद्यात्। अग्नीषोमौ। अमुंचतं। गृभीतान्। आ।
अन्यं। दिवः। मातरिश्वा। जभार। अमथ्नात्। अन्यं। परि। श्येनः। अद्रेः। अग्नीषोमा। ब्रह्म
णा। ववृधाना। उरुं। यज्ञाय। चक्रथुः। ऊं इति। लोकं। ॥ ६॥ अग्नीषोमा। हविषः। प्रऽस्थित ९२

© Dharmartha Trust J&K. Digitized by eGangotri

स्या। वीतं। हर्यतं। वृषणा। जुषेथां। सुऽशर्मणा। सुऽअवसा। हि। भूतं। अथ। धत्तं। यज
मानाय। शं। योः। यः। अग्नीषोमा। हविषा। सपर्यात्। देवद्रीचा। मनसा। यः। घृतेन।
तस्य। व्रतं। रक्षतं। पातं। अंहसः। विशे। जनाय। महि। शर्म। यच्छतं। अग्नीषोमा। सऽवे
दसा। सहूती इति सऽहूती। वनतं। गिरः। सं। देवऽत्रा। बभूवथुः। अग्नीषोमौ। अनेन।
वां। यः। वां। घृतेन। दाशति। तस्मै। दीदयतं। बृहत्। अग्नीषोमौ। इमानि। नः। युवं। ह
व्या। जुजोषतं। आ। यातं। उप। नः। सचा। अग्नीषोमा। पिपृतं। अर्वतः। नः। आ। प्यायं
तां। उस्रियाः। हव्यऽसूदः। अस्मे इति। बलानि। मघवत्ऽसु। धत्तं। कृणुतं। नः। अध्वरं।

© Dharmartha Trust J&K. Digitized by eGangotri

प्र.प. श्रुष्टिऽमंतं ॥ २० ॥ इमं । स्तोमं । अर्हते । जातऽवेदसे । रथंऽइव । सं । महेम । मनीषया । भद्रा । हि । नः ।
९३ प्रऽमतिः । अस्य । संऽसदि । अग्ने । सख्ये । मा । रिषाम । वयं । तव । यस्मै । त्वं । आऽयजसे । सः । सा
93 धति । अनर्वा । क्षेति । दधते । सुऽवीर्यं । सः । तूताव । न । एनं । अश्नोति । अंहतिः ॥ ० ॥ शकेम । त्वा ।
संऽइधं । साधय । धियः । त्वेइति । देवाः । हविः । अदंति । आऽहुतं । त्वं । आदित्यान् । आ । वह । तान् ।
हि । उश्मसि ॥ ० ॥ भराम । इध्मं । कृणवाम । हवींषि । ते । चितयंतः । पर्वणाऽपर्वणा । वयं । जीवात
वे । प्रऽतरं । साधय । धियः ॥ ० ॥ विशां । गोपाः । अस्य । चरंति । जंतवः । द्विऽपत् । च । यत् । उत । चतुःऽ
पत् । अक्तुऽभिः । चित्रः । प्रऽकेतः । उषसः । महान् । असि ॥ ३० ॥ त्वं । अध्वर्युः । उत । होता । असि । ९३

© Dharmartha Trust J&K. Digitized by eGangotri

पूर्व्यः। प्रऽशास्ता। पोता। जनुषा। पुरःऽहितः। विश्वाः। विद्वान्। आर्त्विज्या। धीर। पुष्यसि।
७ यः। विश्वतः। सुऽप्रतीकः। सऽदृङ्। असि। दूरे। चित्। सन्। तळित्ऽइव। अति। रोच
से। रात्र्याः। चित्। अंधः। अति। देव। पश्यसि। ८ पूर्वे। देवाः। भवतु। सुन्वतः। रथः। अस्मा
कं। शंसः। अभि। अस्तु। दुःऽध्यः। तत्। आ। जानीत। उत। पुष्यत। वचः। ९ वधैः। दुःऽशंसा
न्। अप। दुःऽध्यः। जहि। दूरे। वा। ये। अंति। वा। के। चित्। अत्रिणः। अथ। यज्ञाय। गृणते।
सुऽगं। कृधि। १० यत्। अयुक्थाः। अरुषा। रोहिता। रथे। वातऽजूता। वृषभस्यऽइव। ते। र
वः। आत्। इन्वसि। वनिनः। धूमऽकेतुना। ११।। ३१।। अध। स्वनात्। उत। बिभ्युः। पतत्रिणः।

© Dharmartha Trust J&K. Digitized by eGangotri

रथेभ्यः।

ग.प. द्रप्साः। यत्। ते। यवसऽअदः। वि। अस्थिरन्। सुऽगं। तत्। ते। तावकेभ्यः। ० अयं। मित्रस्य
९४ । वरुणस्य। धायसे। अवऽयातां। मरुतां। हेळः। अद्भुतः। मृळ। सु। नः। भूतु। एषां। म
नः। पुनः। ० देवः। देवानां। असि। मित्रः। अद्भुतः। वसुः। वसूनां। असि। चारुः। अध्व
94 रे। शर्मन्। स्याम। तव। सप्रथःऽतमे। ० तत्। ते। भद्रं। यत्। संऽइद्धः। स्वे। दमे। सोमऽ
आहुतः। जरसे। मृळयत्ऽतमः। दधासि। रत्नं। द्रविणं। च। दाशुषे। ० यस्मै। त्वं।
सुऽद्रविणः। ददाशः। अनागाः। त्वं। अदिते। सर्वऽताता। यं। भद्रेण। शवसा। चोद
यासि। प्रजाऽवता। राधसा। ते। स्याम। सः। त्वं। अग्ने। सौभगऽत्वस्य। विद्वान्। ९४

© Dharmartha Trust J&K. Digitized by eGangotri

अस्माकं । आयुः । प्र । तिरा । इह । देवाः ॥ तत् । नः । मित्रः । वरुणः । ममहंतां । अदितिः । सिंधुः ।
पृथिवी । उत । द्यौः ॥ १२ ॥ इति प्रथमाष्टके षष्ठोध्यायः समाप्तः ॥ ॥ ॥ ॥
ॐ हवे एकादशोषसायवाग्नयेसप्तलथानवद्रविणोदसेपनोष्टोस्तुचयेगायत्रंवैश्वा
नरस्यत्वचंवैश्वानरीयंजातवेदसएकाजातवेदस्यमेतदादीन्येकभूयांसिसूक्तसह
स्रमेतत्तुकश्यपआर्षंसयोवृषेकोनावार्षागिराऋज्राश्वांबरीषसहदेवभयमान
सुराधसःप्रमंदिनएकादशकुत्सअश्वस्तुत्रिष्टुबंतमाद्यागर्भस्त्राविण्यउपनिष
दिमांतेसात्रिष्टुप्तत्रस्तोयानर्नवचंइमाएकोनास्प्यास्त्रितोवावैश्वदेवंहिपांक्तमंत्या

© Dharmartha Trust J&K. Digitized by eGangotri

पृ० म०

९५

त्रिष्टुबष्टमीमहाबृहतीयवमध्यंद्वंमित्रंसप्तात्रिष्टुबंतंयज्ञस्तुचंयद्विंद्राग्नीसप्तौनै

द्राग्नंतुविंद्यष्टौततंनवाभंदंतुपंचम्यंसेत्रिष्टुभौतक्षन्यंचास्यात्रिष्टुब्वीळेपंचाधिकाग्नि

नमाद्यौपादौलिंगोक्तदेवतावंस्येत्रिष्टुभौ॥द्वेइति।विरूपेइति।विऽरूपे।चरतः।

95

स्वर्थेइति।सुऽअर्थे।अन्यान्याऽअन्या।वत्सं।उप।धापयेतेइति॥हरिः।अन्यस्यां।भवति।स्व

धाऽवान्।शुक्रः।अन्यस्यां।ददृशे।सुऽवर्चाः॥दश।इमं।त्वष्टुः।जनयंत।गर्भं।अतंद्रा

सः।युवतयः।विऽभृत्रं॥तिग्मऽअनीकं।स्वऽयशसं।जनेषु।विऽरोचमानं।परि।सीं।नयं

ति॥त्रीणि।जाना।परि।भूषंति।अस्य।समुद्रे।एकं।दिवि।एकं।अप्ऽसु॥पूर्वां।अनु।प्र।दिशं। ९५

© Dharmartha Trust J&K. Digitized by eGangotri

पार्थिवानां। ऋतून्। प्रऽशासत्। वि। दधौ। अनुऽस्थु। कः। इमं। वः। निण्यं। आ। चिकेत। वत्सः। मा
तृः। जनयत। स्वधाभिः। बह्वीनां। गर्भः। अपसां। उपऽस्थात्। महान्। कविः। निः। चरति। स्वधाऽ
वान्। आविःऽत्यः। वर्धते। चारुः। आसु। जिह्मानां। ऊर्ध्वः। स्वऽयशाः। उपऽस्थे। उभे इति। त्व
ष्टुः। बिभ्यतुः। जायमानात्। प्रतीची इति। सिंहं। प्रति। जोषयेते इति। १। उभे इति। भद्रे इ
ति। जोषयेते इति। न। मेने इति। गावः। न। वाश्राः। उप। तस्थुः। एवैः। सः। दक्षाणां। दक्षऽप
तिः। बभूव। अंजंति। यं। दक्षिणतः। हविःऽभिः। उत्। यंयमीति। सविताऽइव। बाहू इति।
उभे इति। सिचौ। यतते। भीमः। ऋंजन्। उत्। शुक्रं। अत्कं। अजते। सिमस्मात्। नवा।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ मातृऽभ्यः। वसना। जहाति॥ त्वेषं। रूपं। कृणुते। उत्ऽतरं। यत्। संऽपृंचानः। सदने। गोभिः।
९६ अत्ऽभिः॥ कविः। बुध्नं। परि। मर्मृज्यते। धीः। सा। देवऽताता। संऽइतिः। बभूव॥ उरु। ते। ज्र
यः। परि। एति। बुध्नं। विऽरोचमानं। महिषस्य। धाम॥ विश्वेभिः। अग्ने। स्वयशःऽभिः। इद्धः। अ
96 दब्धेभिः। पायुऽभिः। पाहि। अस्मान्॥ धन्वन्। स्रोतः। कृणुते। गातुं। ऊर्मिं। शुक्रैः। ऊर्मिऽभिः।
अभि। नक्षति। क्षां॥ विश्वा। सनानि। जठरेषु। धत्ते। अंतः। नवासु। चरति। प्रऽसूषु॥ एव।
नः। अग्ने। संऽइधा। वृधानः। रेवत्। पावक। श्रवसे। वि। भाहि॥ ०॥ ५॥ सः। प्रत्नऽथा। सहसा।
जायमानः। सद्यः। काव्यानि। बट्। अधत्त। विश्वा॥ आपः। च। मित्रं। धिषणा। च। साधन्। देवाः। ९६

© Dharmartha Trust J&K. Digitized by eGangotri

अग्निं। धारयन्। द्रविणःऽदां॥ सः। पूर्वया॥ निऽविदा। कव्यता। आयोः। इमाः। प्रऽजाः। अजनय
त्। मनूनां॥ विवस्वता। चक्षसा। द्यां। अपः। च। ०॥ तं। ईळत। प्रथमं। यज्ञऽसाधं। विशः।
आरीः। आऽहुतं। ऋंजसानं। ऊर्जः। पुत्रं। भरतं। सृप्रऽदानुं। ०॥ सः। मातरिश्वा। पुरुऽवारऽपु
ष्टिः। विदत्। गातुं। तनयाय। स्वःऽवित्॥ विशां। गोपाः। जनिता। रोदस्योः। ०॥ नक्तोषसा॥
वर्णं। आमेम्याने इत्याऽमेम्याने। धापयेते इति। शिशुं। एकं। समीची इति संऽईची॥
द्यावाक्षामा। रुक्मः। अंतः। वि। भाति। ०॥ ३॥ रायः। बुध्नः। संऽगमनः। वसूनां। य
ज्ञस्य। केतुः। मन्मऽसाधनः। वेरिति वेः॥ अमृतऽत्वं। रक्षमाणासः। एनं। ०॥ नु। च। पुरा। च।

© Dharmartha Trust J&K. Digitized by eGangotri

१· ७· सहनां । रयीणां । जातस्य । च । जायमानस्य । च । क्षां । सतः । च । गोपां । भवतः । च । भूरेः ॥ ० ॥ द्रवि

९८ णःऽदाः । द्रविणसः । तुरस्य । द्रविणःऽदाः । सनरस्य । प्र । यंसत् ॥ द्रविणःऽदाः । वीरऽवतीं । इ

षं । नः । द्रविणःऽदाः । रासते । दीर्घं । आयुः ॥ ० ॥ ४ ॥ अप । नः । शोशुचत् । अघं । अग्ने । शुशुग्धि ।

97 आ । रयिं ॥ ० ॥ सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे ॥ ० ॥ प्र । यत् । भंदिष्ठः । एषां ।

प्र । अस्माकासः । च । सूरयः ॥ ० ॥ प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र । ते । वयं ॥ ० ॥

प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यंति । भानवः ॥ ० ॥ त्वं । हि । विश्वतःऽमुख । विश्वतः । प

रिऽभूः । असि ॥ ० ॥ द्विषः । नः । विश्वतःऽमुख । अति । नावाऽइव । पारय ॥ ० ॥ सः । नः । सिंधुंऽइव । ९८

© Dharmartha Trust J&K. Digitized by eGangotri

नावया। अति। पर्षं। स्वस्तये॥ ०॥ ५॥ वैश्वानरस्य। सु॒ऽमतौ। स्याम। राजा। हि। कं। भुवनानां।
अभिऽश्रीः॥ इतः। जातः। विश्वं। इदं। वि। चष्टे। वैश्वानरः। यतते। सूर्येण॥ पृष्टः। दिवि। पृष्टः।
अग्निः। पृथिव्यां। पृष्टः। विश्वाः। ओषधीः। आ। विवेश। वैश्वानरः। सहसा। पृष्टः। अग्निः। सः।
नः। दिवा। सः। रिषः। पातु। नक्तं। वैश्वानर। तव। तत्। सत्यं। अस्तु। अस्मान्। रायः। मघऽवानः।
सचंतां॥ ०॥ ६॥ जातऽवेदसे। सुनवाम। सोमं। अरातिऽयतः। नि। दहाति। वेदः॥ सः। नः। प।
र्षत्। अति। दुःऽगानि। विश्वा। नावाऽइव। सिंधुं। दुःऽइता। अति। अग्निः॥ ७॥ सः। यः। वृष्णा।
वृष्ण्येभिः। सं॑ऽओकाः। महः। दिवः। पृथिव्याः। च। संऽराट्॥ सतीनऽसत्वा। हव्यः। भरेषु। मरुत्वान्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ नः।भवतु।इंद्रः।ऊती॥यस्य।अनाप्तः।सूर्यस्यऽइव।यामः।भरेऽभरे।वृत्रऽहा।शुष्मः।अस्ति॥
५ वृषन्ऽतमः।सखिऽभिः।स्वेभिः।एवैः।०॥दिवः।न।यस्य।रेतसः।दुघानाः।पंथासः।यंति।शवसा।
अपरिऽह्वृताः॥तरतऽद्वेषाः।ससहिः।पौंस्येभिः।०॥सः।अंगिरःऽभिः।अंगिरःऽतमः।भूत्।वृषा।वृ
98 षऽभिः।सखिऽभिः।सखा।सन्॥ऋग्मिऽभिः।ऋग्मी।गातुऽभिः।ज्येष्ठः।०॥सः।सूनुऽभिः।न।रुद्रेभिः।
ऋभ्वा।नृऽसह्ये।ससह्वान्।अमित्रान्॥सऽनीळेभिः।श्रवस्यानि।तूर्वन्।०।४॥सः।मन्युऽमीः।
सऽमदनस्य।कर्ता।अस्माकेभिः।नृऽभिः।सूर्यं।सनत्॥अस्मिन्।अहन्।सत्ऽपतिः।पुरुऽहू ५
तः।०॥तं।ऊतयः।रणयन्।शूरऽसातौ।तं।क्षेमस्य।क्षितयः।कृण्वत।त्रां॥सः।विश्वस्य।करुण

© Dharmartha Trust J&K. Digitized by eGangotri

स्या।इंद्रो।एकः।०।।तं।अप्संत।शवसः।उत्ऽसवेषु।नरः।नरं।अवसे।तं।धनाय।।सः।अंधे।
चित्।तमसि।ज्योतिः।विदत्।०।।सः।सव्येन।यमति।व्राधतः।चित्।सः।दक्षिणे।संऽगृभी
ता।कृतानि।।सः।कीरिणा।चित्।सनिता।धनानि।०।।सः।ग्रामेभिः।सनिता।सः।रथेभिः।
विदे।विश्वाभिः।कृष्टिऽभिः।नु।अद्य।।सः।पौंस्येभिः।अभिऽभूः।अशस्तीः।०।१२।।सः।जा
मिऽभिः।यत्।संऽअजाति।मीळ्हे।अजामिऽभिः।वा।पुरुऽहूतः।एवैः।अपां।तोकस्य।तन
यस्य।जेषे।०।।सः।वज्रऽभृत्।दस्युऽहा।भीमः।उग्रः।सहस्रऽचेताः।शतऽनीथः।ऋभ्वा।।
चम्रीषः।न।शवसा।पांचऽजन्यः।०।।तस्य।वज्रः।क्रंदति।स्मत्।स्वःऽसाः।दिवः।न।त्वेषः।र

© Dharmartha Trust J&K. Digitized by eGangotri

पृ. भ्र.

९९

99

वयः। शिमीऽवान्॥ तं। सऽवंतः। सनयः। तं। धनानि॥ ०॥ यस्य। अजस्रं। शवसा। मानं। उक्थं। परिऽ
भुजत्। रोदसी इति। विश्वतः। सीं॥ सः। पारिषत्। क्रतुऽभिः। मंदसानः॥ ०॥ न। यस्य। देवाः। देवता।
न। मर्ताः। आपः। चन। शवसः। अंतं। आपुः॥ सः। प्रऽरिक्वा। त्वक्षसा। क्ष्मः। दिवः। च॥ ०॥ १०॥ रोहित्।
श्यावा। सुमत्ऽअंशुः। ललामीः। द्युक्षा। राये। ऋज्रऽअश्वस्य॥ वृषण्ऽवंतं। बिभ्रती। धूः। सु। रथं।
मंद्रा। चिकेत। नाहुषीषु। विक्षु॥ एतत्। त्यत्। ते। इंद्र। वृष्णे। उक्थं। वार्षागिराः। अभि। गृणंति।
राधः॥ ऋज्रऽअश्वः। प्रष्टिऽभिः। अंबरीषः। सहऽदेवः। भयमानः। सुऽराधाः॥ दस्यून्। शिम्यून्।
च। पुरुऽहूतः। एवैः। हत्वा। पृथिव्यां। शर्वा। नि। बर्हीत्॥ सनत्। क्षेत्रं। सखिऽभिः। श्वित्न्ये ९९

© Dharmartha Trust J&K. Digitized by eGangotri

भिः। सनुतः। सूर्यं। सनन्तम्। अपः। सुऽवज्रः॥ विश्वाहा। इन्द्रः। अधिऽवक्ता। नः। अस्तु। अपरिऽहृ
ताः। सनुयाम। वाजं॥ ०॥ १९॥ प्र। मन्दिने। पितुऽमत्। अर्चत। वचः। यः। कृष्णऽगर्भाः। निःऽ
अहन्। ऋजिश्वना॥ अवस्यवः। वृषणं। वज्रऽदक्षिणं। मरुत्वन्तं। सख्याय। हवामहे॥ यः।
विऽअंसं। जहृषाणेन। मन्युना। यः। शंबरं। यः। अहन्। पिप्रुं। अव्रतं॥ इन्द्रः। यः। शुष्णं। अ
शुषं। नि। अवृणक्॥ ०॥ यस्य। द्यावापृथिवी इति। पौंस्यं। महत्। यस्य। व्रते। वरुणः। यस्य। सूर्यः॥
यस्य। इन्द्रस्य। सिन्धवः। सश्चति। व्रतं॥ ०॥ यः। अश्वानां। यः। गवां। गोऽपतिः। वशी। यः। आरि
तः। कर्मणिऽकर्मणि। स्थिरः॥ वीळोः। चित्। इन्द्रः। यः। असुन्वतः। वधः॥ ०॥ यः। विश्वस्य। जग

© Dharmartha Trust J&K. Digitized by eGangotri

पृ. प्र. तः। प्राणतः। पतिः। यः। ब्रह्मणे। प्रथमः। गाः। अविंदत्। इंद्रः। यः। दस्यून्। अधरान्। अवऽअति
१०० रत्। ०। यः। शूरेभिः। हव्यः। यः। च। भीरुऽभिः। यः। धावत्ऽभिः। हूयते। यः। च। जिग्युऽभिः। इं
द्रं। यं। विश्वा। भुवना। अभि। संऽदधुः। ०। ३। रुद्राणां। एति। प्रऽदिशा। विऽचक्षणः। रुद्रे
100 भिः। योषा। तनुते। पृथु। ज्रयः। इंद्रं। मनीषा। अभि। अर्चति। श्रुतं। ०। यत्। वा। मरुत्वः।
परमे। सधऽस्थे। यत्। वा। अवमे। वृजने। मादयासे। अतः। आ। याहि। अध्वरं। नः। अछ। त्वाऽ
या। हविः। चकृम। सत्यऽराधः। त्वाऽया। इंद्र। सोमं। सुसुम। सुऽदक्ष। ०। ब्रह्मऽवाहः। अध।
नियुत्वः। सऽगणः। मरुत्ऽभिः। अस्मिन्। यज्ञे। बर्हिषि। मादयस्व। मादयस्व। हरिऽभिः। ये। १००

© Dharmartha Trust J&K. Digitized by eGangotri

ते। इंद्र। वि। स्यस्व। शिप्रे इति। वि। सृजस्व। धेने इति॥ आ। त्वा। सुऽशिप्र। हरयः। वहंतु। उशन्। हव्या
नि। प्रति। नः। जुषस्व॥ मरुत्वःऽस्तोत्रस्य। वृजनस्य। गोपाः। वयं। इंद्रेण। सनुयाम। वाजं॥ ०॥ १३॥ इमां।
ते। धियं। प्र। भरे। महः। महीं। अस्य। स्तोत्रे। धिषणा। यत्। ते। आनजे॥ तं। उत्ऽसवे। च। प्रऽसवे।
च। ससहिं। इंद्रं। देवासः। शवसा। अमदन्। अनु॥ अस्य। श्रवः। नद्यः। सप्त। बिभ्रति। द्यावाक्षामा।
पृथिवी। दर्शतं। वपुः॥ अस्मे इति। सूर्याचंद्रमसा। अभिऽचक्षे। श्रद्धे। कं। इंद्र। चरतः। विऽतर्तुरं॥ तं।
स्म। रथं। मघऽवन्। प्र। अव। सातये। जैत्रं। यं। ते। अनुऽमदाम। संऽगमे॥ आजा। नः। इंद्र। मनसा।
पुरुऽस्तुत। त्वायत्ऽभ्यः। मघऽवन्। शर्म। यच्छ। नः॥ वयं। जयेम। त्वया। युजा। वृतं। अस्माकं। अंं

© Dharmartha Trust J&K. Digitized by eGangotri

यों।उत।अव।भरे॑ऽभरे॥अस्मभ्यं।इंद्र।वरिवः।सुऽगं।कृधि।प्र।शत्रूणां।मघऽवन्।वृष्ण्या।रुज॥
नाना।हि।त्वा।हवमानाः।जनाः।इमे।धनानां।धर्त्तः।अवसा।विपन्यवः॥अस्माकं।स्म।रथं।
आ।तिष्ठ।सातये।जैत्रं।हि।इंद्र।निऽभृतं।मनः।तव॥१४॥गोऽजिता।बाहू इति।अमितऽक्रतुः।
सिमः।कर्मन्ऽकर्मन्।शतंऽऊतिः।खजंऽकरः॥अकल्पः।इंद्रः।प्रतिऽमानं।ओजसा।अथ।ज
नाः।वि।ह्वयंते।सिसासवः॥उत।ते।शतात्।मघऽवन्।उत।च।भूयसः।उत।सहस्रात्।रिरि
चे।कृष्टिषु।श्रवः॥अमात्रं।त्वा।धिषणा।तित्विषे।मही।अध।वृत्राणि।जिघ्नसे।पुरंऽद
र॥त्रिऽविष्टिऽधातु।प्रतिऽमानं।ओजसः।तिस्रः।भूमीः।नृऽपते।त्रीणि।रोचना।अति।

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रं। विश्वं। भुवनं। वि। ववक्षिथ। अशत्रुः। इंद्र। जनुषा। सनात्। असि॥ त्वां। देवेषु। प्रथमं। हवामहे।
त्वं। बभूथ। पृतनासु। ससहिः॥ सः। इमं। नः। कारुं। उपऽमन्युं। उत्ऽभिदं। इंद्रः। कृणोतु। प्रऽस
वे। रथं। पुरः॥ त्वं। जिगेथ। न। धना। रुरोधिथ। अर्भेषु। आजा। मघऽवन्। महत्ऽसु। च॥ त्वां।
उग्रं। अवसे। सं। शिशीमसि। अथ। नः। इंद्र। हवनेषु। चोदय॥ ॥१५॥ न। त्वा। नु। इंद्रियं। परमं। प
राचैः। अधारयंत। कवयः। पुरा। इदं॥ क्षमा। इदं। अन्यत्। दिवि। अन्यत्। अस्य। सं। ईमिति।
पृच्यते। समनाऽइव। केतुः॥ सः। धारयत्। पृथिवीं। पप्रथत्। च। वज्रेण। हत्वा। निः। अपः।
ससर्ज। अहन्। अहिं। अभिनत्। रौहिणं। वि। अहन्। विऽअंसं। मघऽवा। शचीभिः॥ सः। जा

© Dharmartha Trust J&K. Digitized by eGangotri

पु॰ प्र॰ १०२

102

तूऽभर्मा । श्रत्ऽदधानः । ओजः । पुरः । विऽभिंदन् । अचरत् । वि । दासीः ॥ विद्वान् । वज्रिन् । दस्यवे । हेतिं ।
अस्य । आर्यं । सहः । वर्धय । द्युम्नं । इंद्र ॥ तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यं । मघऽवा ।
नाम । बिभ्रत् । उपऽप्रयन् । दस्युऽहत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥ तत् ।
अस्य । इदं । पश्यत । भूरि । पुष्टं । श्रत् । इंद्रस्य । धत्तन । वीर्याय ॥ सः । गाः । अविंदत् । सः । अविं
दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥ १६ ॥ भूरिऽकर्मणे । वृषभाय । वृष्णे ।
सत्यऽशुष्माय । सुनवाम । सोमं ॥ यः । आऽदृत्य । परिपंथीःऽइव । शूरः । अयज्वनः । विऽभज
न् । एति । वेदः ॥ तत् । इंद्र । प्रऽइव । वीर्यं । चकर्थ । यत् । ससंतं । वज्रेण । अबोधयः । अहिं ॥ १०२

© Dharmartha Trust J&K. Digitized by eGangotri

अनु । त्वा । पत्नीः । हृषितं । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा ॥ शुष्णं । पिप्रुं । कुय

वं । वृत्रं । इंद्र । यदा । अवधीः । वि । पुरः । शंबरस्य ॥ ० ॥ २ ॥ योनिः । ते । इंद्र । निऽसदे । अका

रि । तं । आ । नि । सीद । स्वानः । न । अर्वा । विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः ।

वहीयसः । प्रऽपित्वे ॥ ओ इति । त्ये । नरः । इंद्रं । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः ।

जगम्यात् । देवासः । मन्युं । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सुविताय । वर्णं ॥ अव । त्मना ।

भरते । केतऽवेदाः । अव । त्मना । भरते । फेनं । उदन् । क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इ

ति । ते इति । स्यातां । प्रऽवणे । शिफायाः ॥ युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । रा

© Dharmartha Trust J&K. Digitized by eGangotri

पु. श्रु.

१०३

103

ष्टि। शूरः। अंजसी। कुलिशी। वीरऽपत्नी। पयः। हिन्वानाः। उदऽभिः। भरंते॥ प्रति। यत्। स्या। नी
था। अदर्शि। दस्योः। ओकः। न। अछ। सदनं। जानती। गात्। अध। स्म। नः। मघऽवन्। चर्कृतात्।
इत्। मा। नः। मघाऽइव। निःऽसपी। परा। दाः॥ १८॥ सः। त्वं। नः। इंद्र। सूर्ये। सः। अप्ऽसु। अना
गाःऽत्वे। आ। भज। जीवऽशंसे। मा। अंतरां। भुजं। आ। रिरिषः। नः। श्रद्धितं। ते। महते। इंद्रि
याय॥ अध। मन्ये। श्रत्। ते। अस्मै। अधायि। वृषा। चोदस्व। महते। धनाय। मा। नः। अकृते।
पुरुऽहूत। योनौ। इंद्र। क्षुध्यत्ऽभ्यः। वयः। आऽसुतिं। दाः॥ मा। नः। वधीः। इंद्र। मा। परा। दाः।
मा। नः। प्रिया। भोजनानि। प्र। मोषीः। आंडा। मा। नः। मघऽवन्। शक्र। निः। भेत्। मा। नः। पा १०३

© Dharmartha Trust J&K. Digitized by eGangotri

त्रा। भूत्। सहऽजानुषाणि। अर्वाङ्। आ। इहि। सोमऽकामं। त्वा। आहुः। अयं। सुतः। तस्य। पि

ब। मदाय। उरुऽव्यचाः। जठरे। आ। वृषस्व। पिताऽइव। नः। शृणुहि। हूयमानः॥ १५॥ चंद्रमाः।

अप्ऽसु। अंतः। आ। सुऽपर्णः। धावते। [illegible] दिवि। न। वः। हिरण्यऽनेमयः। पदं। विंदंति। विऽद्युतः।

वित्तं। मे। अस्य। रोदसीइति। अर्थं। इत्। वै। ऊंइति। अर्थिनः। आ। जाया। युवते। पतिं। तुंजातेइति। वृष्ण्यं।

पयः। परिऽदाय। रसं। दुहे॥ ०॥ मोइति। सु। देवाः। अदः। स्वः। अव। पादि। दिवः। परि। मा। सोम्यस्य। शंऽभु

वः। शूने। भूम। कदा। चन॥ ०॥ यज्ञं। पृच्छामि। अवमं। सः। तत्। दूतः। वि। वोचति। क्व। ऋतं। पूर्व्यं। गतं। कः।

तत्। बिभर्ति। नूतनः॥ ०॥ अमीइति। ये। देवाः। स्थन। त्रिषु। आ। रोचने। दिवः। क्व। वः। ऋतं। क्व।

© Dharmartha Trust J&K. Digitized by eGangotri

प० प्र०
१०४
104

अनृतं। घ्नं। प्रऽत्ना। वः। आऽकूतिः। ०॥२०॥ ऋतं। वः। सत्यस्य। धर्णसि। ऋतं। वरुणस्य। चक्षणं॥ ऋतं।
अर्यम्णः। मुहः। पथा। अति। क्रामेम। दुःऽध्यः। ०॥ अहं। सः। अस्मि। यः। पुरा। सुते। वदामि।
कानि। चित्। तं। मा। व्यंति। आऽध्यः। वृकः। न। तृष्णऽजं। मृगं। ०॥ सं। मा। तपंति। अभितः।
सपत्नीःऽइव। पर्शवः॥ मूषः। न। शिश्ना। वि। अदंति। मा। आऽध्यः। स्तोतारं। ते। शतक्रतो।
इति शतऽक्रतो। ०॥ अमी इति। ये। सप्त। रश्मयः। तत्र। मे। नाभिः। आऽतता। त्रितः। तत्।
वेद। आप्त्यः। सः। जामिऽत्वाय। रेभति। ०॥ अमी इति। ये। पंच। उक्षणः। मध्ये। तस्थुः। महः।
दिवः। देवऽत्रा। नु। प्रऽवाच्यं। सध्रीचीनाः। नि। ववृतुः। ०॥२१॥ सुऽपर्णाः। एते। आसते। म १०४

© Dharmartha Trust J&K. Digitized by eGangotri

ध्ये। आऽराधने। दिवः॥ ते। सेधन्ति। पथः। वृकं। तरन्तं। यह्वतीः। अपः॥०॥ नव्यं। तत्। उक्थ्यं। हितं।
देवासः। सुऽप्रवाचनं॥ ऋतं। अर्षन्ति। सिन्धवः। सत्यं। ततान। सूर्यः॥०॥ अग्ने। तव। त्यत्। उक्थ्यं।
देवेषु। अस्ति। आप्यं॥ सः। नः। सत्तः। मनुष्वत्। आ। देवान्। यक्षि। विदुःऽतरः॥०॥ सत्तः। होता।
मनुष्वत्। आ। देवान्। अच्छ। विदुःऽतरः॥ अग्निः। हव्या। सुसूदति। देवः। देवेषु। मेधिरः॥०॥
ब्रह्म। कृणोति। वरुणः। गातुऽविदं। तं। ईमहे॥ वि। ऊर्णोति। हृदा। मतिं। नव्यः। जायतां। ऋतं॥०॥
॥२२॥ असौ। यः। पन्थाः। आदित्यः। दिवि। प्रऽवाच्यं। कृतः॥ न। सः। देवाः। अतिऽक्रमे। तं। म
र्तासः। न। पश्यथ॥०॥ त्रितः। कूपे। अवऽहितः। देवान्। हवते। ऊतये॥ तत्। शुश्राव। बृहस्पतिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प० म०

१०५

३

हण्वन्। अंहूरणात्। उरु। ०। अरुणः। मा। सकृत्। वृकः। पथा। यंतं। ददर्श। हि। उत्। जिहीते। निः
चाय्य। तष्टाऽइव। पृष्टिऽआमयी। ०। एना। आंगूषेण। वयं। इंद्रऽवंतः। अभि। स्याम। वृजने।
सर्वऽवीराः। ०। १८। इंद्रं। मित्रं। वरुणं। अग्निं। ऊतये। मारुतं। शर्धः। अदितिं। हवामहे। रथं।
न। दुःऽगात्। वसवः। सुऽदानवः। विश्वस्मात्। नः। अंहसः। निः। पिपर्तन। ते। आदित्याः। आ। गत।
सर्वऽतातये। भूत। देवाः। वृत्रऽतूर्ये। शंऽभुवः। ०। अवंतु। नः। पितरः। सुऽप्रवाचनाः। उत। देवी
इति। देवपुत्रे इति देवऽपुत्रे। ऋतऽवृधा। ०। नराशंसं। वाजिनं। वाजयन्। इह। क्षयत्ऽवीरं। पू १०५
षणं। सुम्नैः। ईमहे। ०। बृहस्पते। सदं। इत्। नः। सुऽगं। कृधि। शं। योः। यत्। ते। मनुःऽहितं। तत्।

© Dharmartha Trust J&K. Digitized by eGangotri

ङ

ईमहे॥०॥इंद्रं।कुत्सं।वृत्रऽहनं।शचीऽपतिं।काटे।निऽबाळ्हः।ऋषिः।अह्वत्।ऊतये॥०॥देवैः।
नः।देवी।अदितिः।नि।पातु।देवः।त्राता।त्रायतां।अप्रऽयुछन्॥०॥२४॥यज्ञः।देवानां।प्रति।ए
ति।सुम्नं।आदित्यासः।भवत।मृळयंतः॥आ।वः।अर्वाची।सुऽमतिः।ववृत्यात्।अंहोः।चित्।
या।वरिवोवित्ऽतरा।असत्॥उप।नः।देवाः।अवसा।आ।गमंतु।अंगिरसां।सामऽभिः।स्तूयमा
नाः॥इंद्रः।इंद्रियैः।मरुतः।मरुत्ऽभिः।आदित्यैः।नः।अदितिः।शर्म।यंसत्॥तत्।नः।इंद्रः।
तत्।वरुणः।तत्।अग्निः।तत्।अर्यमा।तत्।सविता।चनः।धात्॥०॥२५॥यः।इंद्राग्नीइति।चित्रऽ
तमः।रथः।वां।अभि।विश्वानि।भुवनानि।चष्टे।तेन।आ।यातं।सऽरथं।तस्थिऽवांसा।अथ।सोम

© Dharmartha Trust J&K. Digitized by eGangotri

पृ. प्र.
१०६
106

स्य । पिबतं । सुतस्य ।। यावत् । इदं । भुवनं । विश्वं । अस्ति । उरुऽव्यचा । वरिमता । गभीरं । तावान् । अयं । पा
तवे । सोमः । अस्तु । अरं । इंद्राग्नी इति । मनसे । युवऽभ्यां ।। चक्राथे इति । हि । सध्र्यक् । नाम । भद्रं । सध्री
चीना । वृत्रऽहना । उत । स्थः । तौ । इंद्राग्नी इति । सध्र्यंचा । निऽसद्य । वृष्णः । सोमस्य । वृषणा । आ ।
वृषेथां ।। संऽइद्धेषु । अग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊं इति । तिस्तिराणा ।। तीव्रैः । सोमैः ।
परिऽसिक्तेभिः । अर्वाक् । आ । इंद्राग्नी इति । सौमनसाय । यातं ।। यानि । इंद्राग्नी इति । चक्रथुः । वीर्या
णि । यानि । रूपाणि । उत । वृष्ण्यानि ।। या । वां । प्रत्नानि । सख्या । शिवानि । तेभिः । सोमस्य । पिबतं । सु
तस्य ।। २८ ।। यत् । अब्रवं । प्रथमं । वां । वृणानः । अयं । सोमः । असुरैः । नः । विऽहव्यः ।। तां । सत्यां । श्रद्धां । १०६

© Dharmartha Trust J&K. Digitized by eGangotri

अभि। आ। हि। यातं ॥०॥ यत्। इंद्राग्नी इति। मदथः। स्वे। दुराणे। यत्। ब्रह्मणि। राजनि। वा। यज
त्रा। अतः। परि। वृषणो। आ। हि। यातं ॥०॥ यत्। इंद्राग्नी इति। यदुषु। तुर्वशेषु। यत्। द्रुह्युषु। अनु
षु। पूरुषु। स्थः ॥०॥ यत्। इंद्राग्नी इति। अवमस्यां। पृथिव्यां। मध्यमस्यां। परमस्यां। उत। स्थः ॥०॥
यत्। इंद्राग्नी इति। दिवि। स्थः। यत्। पृथिव्यां। यत्। पर्वतेषु। ओषधीषु। अप्ऽसु ॥०॥ यत्। इंद्रा
ग्नी इति। उत्ऽइता। सूर्यस्य। मध्ये। दिवः। स्वधया। मादयेथे इति ॥०॥ एव। इंद्राग्नी इति। पपिऽवां
सा। सुतस्य। विश्वा। अस्मभ्यं। सं। जयतं। धनानि ॥०॥२७॥ वि। हि। अख्यं। मनसा। वस्यः। इच्छ
न्। इंद्राग्नी इति। ज्ञासः। उत। वा। सऽजातान् ॥ न। अन्या। युवत्। प्रऽमतिः। अस्ति। मह्यं। सः। वां।

© Dharmartha Trust J&K. Digitized by eGangotri

पु॰ प॰ धियं । वाजऽयंती । अतक्षं ॥ अश्वं । हि । भूरिदावत्ऽतरा । वां । विऽजामातुः । उत । वा । घ ।
१०८ स्यालात् ॥ अथ । सोमस्य । प्रऽयती । युवऽभ्यां । इंद्राग्नी इति । स्तोमं । जनयामि । नव्यं ॥ मा ।
छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणां । शक्तीः । अनुऽयच्छमानाः ॥ इंद्राग्निऽभ्यां । कं ।
107 वृषणः । मदंति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थे ॥ युवाभ्यां । देवी । धिषणा । मद
य । इंद्राग्नी इति । सोमं । उशती । सुनोति ॥ तौ । अश्विना । भद्रऽहस्ता । सुपाणी इति सुऽपा
णी । आ । धावतं । मधुना । पृंक्तं । अप्ऽसु ॥ युवां । इंद्राग्नी इति । वसुनः । विऽभागे । तवःऽतमा ।
शुश्रव । वृत्रऽहत्ये ॥ तौ । आऽसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथां । सुत १०८

© Dharmartha Trust J&K. Digitized by eGangotri

स्य ॥ २८ ॥ प्र । चर्षणिऽभ्यः । पृतनाऽहवेषु । प्र । पृथिव्याः । रिरिचाथे इति । दिवः । च । प्र । सिंधुऽभ्यः ।
प्र । गिरिऽभ्यः । महिऽत्वा । प्र । इंद्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥ आ । भरतं । शिक्षतं । वज्र
बाहू इति वज्रऽबाहू । अस्मान् । इंद्राग्नी इति । अवतं । शचीभिः ॥ इमे । नु । ते । रश्मयः । सूर्यस्य ।
येभिः । संऽपितं । पितरः । नः । आसन् ॥ पुरःऽदसा । शिक्षतं । वज्रऽहस्ता । भरेषु ॥ ० ॥ २९ ॥ तं तं मे ।
अपः । तत् । ऊं इति । तायते । पुनः । स्वादिष्ठा । धीतिः । उचथाय । शस्यते ॥ अयं । समुद्रः । इह
विश्वऽदेव्यः । स्वाहाऽकृतस्य । सं । ऊं इति । तृप्णुत । ऋभवः ॥ आऽभोगयं । प्र । यत् । इच्छंतः । ऐतन ।
अपाकाः । प्रांचः । मम । के । चित् । आपयः ॥ सोधन्वनासः । चरितस्य । भूमना । अगच्छत । सवि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ तुः। दाशुषेः। गृहं।। तत्। सविता। वः। अमृतऽत्वं। आ। असुवत। अगोह्यं। यत्। श्रवयंतः।
१०८ ऐतन।। त्यं। चित्। चमसं। असुरस्य। भक्षणं। एकं। संतं। अकृणुत। चतुःऽवयं।। विष्ट्वी। शमी।
तरणिऽत्वेन। वाघतः। मर्तासः। संतः। अमृतऽत्वं। आनशुः।। सौधन्वनाः। ऋभवः। सूरऽचक्षसः।
संवत्सरे। सं। अपृच्यंत। धीतिऽभिः।। क्षेत्रंऽइव। वि। ममुः। तेजनेन। एकं। पात्रं। ऋभवः। जेह
108 मानं।। उपऽस्तुताः। उपऽमं। नाधमानाः। अमर्त्येषु। श्रवः। इच्छमानाः।। ३०।। आ। मनीषां। अंतरि
क्षस्य। नृऽभ्यः। स्रुचाऽइव। घृतं। जुहवाम। विद्मना।। तरणिऽत्वा। ये। पितुः। अस्य। सश्चिरे।
ऋभवः। वाजं। अरुहन्। दिवः। रजः।। ऋभुः। नः। इंद्रः। शवसा। नवीयान्। ऋभुः। वाजेभिः। वसुः १०८

© Dharmartha Trust J&K. Digitized by eGangotri

भिः । वसुः । ददिः । युष्माकं । देवाः । अवसा । अहनि । प्रिये । अभि । तिष्ठेम । पृत्सुतीः । असुन्वतां ।
निः । चर्मणः । ऋभवः । गां । अपिंशत । सं । वत्सेन । असृजत । मातरं । पुनरिति ॥ सौधन्वनासः । सुऽअ
पस्यया । नरः । जिव्री इति । युवाना । पितरा । अकृणोतन ॥ वाजेभिः । नः । वाजऽसातौ । अविड्ढि । ऋभुऽ
चित्रं । आ मान् । इंद्र । दर्षि । राधः ॥ ९ ॥ २१ ॥ तक्षन् । रथं । सुऽवृतं । विद्मना । अपसः । तक्षन् । हरीइति । इंद्रऽवाहा ।
वृषण्वसूइति वृषण्ऽवसू ॥ तक्षन् । पितृऽभ्यां । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरं । सचाऽ जा
भुवं ॥ आ । नः । यज्ञाय । तक्षत । ऋभुऽमत् । वयः । क्रत्वे । दक्षाय । सुप्रजाऽवतीं । इषं ॥ यथा । क्षयाम । सर्वऽवी
रया । विशा । तत् । नः । शर्धाय । धासथ । सु । इंद्रियं ॥ आ । तक्षत । सातिं । अस्मभ्यं । ऋभवः । सातिं । रथाय ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ऋ॰
१०९
109

सातिं। अर्वते। नरः॥ सातिं। नः। जैत्रीं। सं। महेत। विश्वहा। जामिं। अजामिं। पृतनासु। सक्षणिं। ऋभुक्षणं।
इंद्रं। आ। हुवे। ऊतये। ऋभून्। वाजान्। मरुतः। सोमऽपीतये। उभा। मित्रावरुणा। नूनं। अश्विना। ते।
नः। हिन्वंतु। सातये। धिये। जिषे॥ ऋभुः। भराय। सं। शिशातु। सातिं। समर्यऽजित्। वाजः। अस्मान्। अ
विष्टु॥ ०॥ ३२॥ ईळे। द्यावापृथिवी इति। पूर्वऽचित्तये। अग्निं। घर्मं। सुऽरुचं। यामन्। इष्टये॥ याभिः। भ
रे। कारं। अंशाय। जिन्वथः। ताभिः। ऊं इति। सु। ऊतिऽभिः। अश्विना। आ। गतं॥ युवोः। दानाय। सुऽभराः।
असश्चतः। रथं। आ। तस्थुः। वचसं। न। मंतवे॥ याभिः। धियः। अवथः। कर्मन्। इष्टये॥ ०॥ युवं। तासां।
दिव्यस्य। प्रऽशासने। विशां। क्षयथः। अमृतस्य। मज्मना॥ याभिः। धेनुं। अस्वं। पिन्वथः। नरा॥ ०॥ याभिः। १०९

© Dharmartha Trust J&K. Digitized by eGangotri

परिऽज्मा। तनयस्य। मज्मना। द्विऽमाता। तूर्षु। तरणिः। विऽभूषति। याभिः। त्रिऽमंतुः। अभवत्। विऽ
चक्षणः। ०। याभिः। रेभं। निऽवृतं। सितं। अत्ऽभ्यः। उत्। वंदनं। ऐरयतं। स्वः। दृशे। याभिः। कण्वं।
प्र। सिसासंतं। आवतं। ०॥ ३३॥ याभिः। अंतकं। जसमानं। आ। अरणे। भुज्युं। याभिः। अव्यथिऽभिः।
जिजिन्वथुः। याभिः। कर्कंधुं। वय्यं। च। जिन्वथः। ०। याभिः। शुचंतिं। धनऽसां। सुऽसंसदं। तप्तं। घर्मं।
ओम्याऽवंतं। अत्रये। याभिः। पृश्निऽगुं। पुरुऽकुत्सं। आवतं। ०। याभिः। शचीभिः। वृषणा। प
राऽवृजं। प्र। अंधं। श्रोणं। चक्षसे। एतवे। कृथः। याभिः। वर्तिकां। ग्रसितां। अमुंचतं। ०। याभिः।
सिंधुं। मधुऽमंतं। असश्चतं। वसिष्ठं। याभिः। अजरौ। अजिन्वतं। याभिः। कुत्सं। श्रुतर्यं।

© Dharmartha Trust J&K. Digitized by eGangotri

पु० प्र० नर्यं। आवतं।०॥ याभिः। विश्पलां। धनऽसां। अथर्व्यं। सहस्रऽमीळ्हे। आजौ। अजिन्वतं॥ याभिः।
११० वशं। अश्व्यं। प्रेणिं। आवतं।०॥ ३४॥ याभिः। सुदानू इति सुऽदानू। औशिजाय। वणिजे। दीर्घऽ
पु। श्रवसे। मधु॥ कोशः। असरत॥ कक्षीवंतं। स्तोतारं। याभिः। आवतं।०॥ याभिः। रसां। क्षो
दसा। उद्नः। पिपिन्वथुः। अनश्वं। याभिः। रथं। आवतं। जिषे। याभिः। त्रिऽशोकः। उस्रि
110 याः। उतऽआजत।०॥ याभिः। सूर्यं। परिऽयाथः। पराऽवति। मंधातारं। क्षैत्रऽपत्येषु। आव
तं॥ याभिः। विप्रं। प्र। भरत्ऽवाजं। आवतं।०॥ याभिः। महां। अतिथिऽग्वं। कशःऽजुवं। दिवःऽ
दासं। शंबरऽहत्ये। आवतं॥ याभिः। पूःऽभिद्ये। त्रसदस्युं। आवतं।०॥ याभिः। वम्रं। विऽपि ११०

© Dharmartha Trust J&K. Digitized by eGangotri

पानं। उपऽस्तुतं। कलिं। याभिः। वित्तऽजानिं। दुवस्यथः॥ याभिः। विऽअश्वं। उत। पृथिं। आवतं।
०॥१५॥ याभिः। नरा। शयवे। याभिः। अत्रये। याभिः। पुरा। मनवे। गातुं। ईषथुः॥ याभिः। शा
रीः। आजतं। स्यूमऽरश्मये। ०॥ याभिः। पठर्वा। जठरस्य। मज्मना। अग्निः। न। अदीदेत्। चितः।
इद्धः। अज्मन्। आ॥ याभिः। शर्यातं। अवथः। महाऽधने। ०॥ याभिः। अंगिरः। मनसा। निःऽ
रण्यथः। अग्रं। गच्छथः। विऽवरे। गोऽअर्णसः॥ याभिः। मनुं। शूरं। इषा। संऽआवतं। ०॥ याभिः।
पत्नीः। विऽमदाय। निऽऊहथुः। आ। घ। वा। याभिः। अरुणीः। अशिक्षतं॥ याभिः। सुऽदासे। ऊहथुः।
सुऽदेव्यं। ०॥ याभिः। शंताती इति शंऽताती। भवथः। ददाशुषे। भुज्युं। याभिः। अवथः। याभिः। अध्रिऽ

© Dharmartha Trust J&K. Digitized by eGangotri

गुं ॥ ओम्या ऽ वतीं । सु ऽ भरां । ऋत ऽ स्तुभं ॥०॥ २६ ॥ याभिः । कृशानुं । असने । दुवस्यथः । जवे । याभिः ।
यूनः । अर्वंतं । आवतं । मधु । प्रियं । भरथः । यत् । सरट् ऽ भ्यः ॥०॥ याभिः । नरं । गोषु ऽ युधं । नृ ऽ सह्ये ।
क्षेत्रस्य । साता । तनयस्य । जिन्वथः । याभिः । रथान् । अवथः । याभिः । अर्वतः ॥०॥ याभिः । कुत्सं ।
आर्जुनेयं । शत ऽ क्रतू इति शत ऽ क्रतू । प्र । तुर्वीतिं । प्र । च । दभीतिं । आवतं ॥ याभिः । ध्वसंतिं । पुरु ऽ
संतिं । आवतं ॥०॥ अप्नस्वतीं । अश्विना । वाचं । अस्मे इति । कृतं । नः । दस्रा । वृषणा । मनीषां ॥ अद्यू
त्ये । अवसे । नि । ह्वये । वां ॥०॥ द्यु ऽ भिः । अक्तु ऽ भिः । परि । पातं । अस्मान् । अरिष्टेभिः । अश्विना । सौभ १११
गेभिः ॥०॥ २७ ॥ इति प्रथमाष्टके ७ ॥ हरिः ॐ इदंविंशतिरूपस्यांद्वितीयोर्धचोरात्रेश्चमाल्का

© Dharmartha Trust J&K. Digitized by eGangotri

दशरो इदं हि त्रिष्टुबंतं। चित्रं षट् सौर्यं नासत्याभ्यां पंचाधिको कक्षीवां दैर्घतमस उशिक्प्रसू
त आश्विनं वैमध्व आवामे काशीवांर थं दश आगतं काराध द्वादशौं स्यादुःस्वप्न नाशिन्या
घा गायत्री द्वितीया ककुप् तृतीया [illegible] चतुर्थ्यौ कावि राण्न ष्टरूप्यो पंचमी
तनुशिरा षष्ठ्यक्षरे रुष्हि ग्विष्टार बृहती कृति र्विराट् तिस्रो गायत्र्यः कादि स्त्रोपं चोना वैश्व
देवं वा॥ ८॥ ॐ म॥ इदं। श्रेष्ठं। ज्योतिषां। ज्योतिः। आ। अगात्॥ चित्रः। प्रऽकेतः। अजनिष्ट।
विऽभ्वा। यथा। प्रऽसूता। सवितुः। सवाय। एव। रात्री। उषसे। योनिं। अरैक्। रुश
त्ऽवत्सा। रुशती। श्वेता। आ। अगात्। अरैक्। ऊं इति। कृष्णा। सदनानि। अस्याः।

© Dharmartha Trust J&K. Digitized by eGangotri

प्र.प्र. समानबंधूइतिसमानऽबंधू। अमृतेइति। अनूचीइति। द्यावा। वर्णं। चरतः। आमिना
३.३२ नेइत्याऽमिनाने। समानः। अध्वा। स्वस्रोः। अनंतः। तं। अन्याऽअन्या। चरतः। देवशिष्टे
इतिदेवऽशिष्टे। न। मेथेतेइति। न। तस्थतुः। सुमेकेइति सुऽमेके। नक्तोषसा। सऽमनसा।
विरूपेइति विऽरूपे।०। अचेति। चित्रा। वि। दुरः। नः। आवरित्यावः। प्रऽअर्प्य। जगत्। वि।
ऊँइति। नः। रायः। अख्यत्। उषाः। अजीगरिति। भुवनानि। विश्वा। जिह्मऽश्ये। चरितवे। म
घोनी। आऽभोगये। इष्टये। राये। ऊँइति। त्वं। दभ्रं। पश्यत्ऽभ्यः। उर्विया। विऽचक्षे।०।४।
क्षत्राय। त्वं। श्रवसे। त्वं। महीयै। इष्टये। त्वं। अर्थंऽइव। त्वं। इत्यै। विऽसदृशा। जीविता। अभि ३३२

ऽप्रऽचक्षे । एषा । दिवः । दुहिता । प्रति । अदर्शि । विऽउच्छन्ती । युवतिः । शुक्रऽवासाः । विश्वस्य । ईशा
ना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुऽभगे । वि । उच्छ । पराऽयतीनां । अनु । एति । पाथः । आऽय
तीनां । प्रथमा । शश्वतीनां । विऽउच्छन्ती । जीवं । उत्ऽईरयन्ती । उषाः । मृतं । कं । चन । बोधयन्ती । उषः । य
त् । अग्निं । संऽइधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य । यत् । मानुषान् । यक्ष्यमाणान् । अजी
गरिति । तत् । देवेषु । चकृषे । भद्रं । अप्नः । कियति । आ । यत् । समया । भवाति । याः । विऽऊषुः । याः । च । नू
नं । विऽउच्छान् । अनु । पूर्वीः । कृपते । वावशाना । प्रऽदीध्याना । जोषं । अन्याभिः । एति । आ । ईयुः । ते । ये ।
पूर्वऽतरां । अपश्यन् । विऽउच्छन्तीं । उषसं । मर्त्यासः । अस्माभिः । ऊं इति । नु । प्रतिऽचक्ष्या । अभूत् । आ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ इति। ते। यंति। ये। अपरीषु। पश्यान्। यवयत्ऽद्वेषाः। ऋतऽपाः। ऋतेऽजाः। सुम्नऽवरी। सूनृता।

३३२ ग ईरयंती। सुऽमंगलीः। बिभ्रती। देवऽवीतिं। इह। अद्य। उषः। श्रेष्ठऽतमा। वि। उच्छ। शश्वत्। पुरा। उषाः। २५

वि। उवास। देवी। अथो इति। अद्य। इदं। वि। आवः। मघोनी। अथो इति। वि। उच्छात्। उत्ऽतरान्।

113 अनु। द्यून्। अजरा। अमृता। चरति। स्वधाभिः। वि। अंजिऽभिः। दिवः। आताऽसु। अद्यौत्। अप।

कृष्णां। निःऽनिजं। देवी। आवरित्यावः। प्रऽबोधयंती। अरुणेभिः। अश्वैः। आ। उषाः। याति। सुऽ

युजा। रथेन। आऽवहंती। पोष्या। वार्याणि। चित्रं। केतुं। कृणुते। चेकिताना। ईयुषीणां। उपऽ

मा। शश्वतीनां। विऽभातीनां। प्रथमा। उषाः। वि। अश्वैत्। ३। उत्। ईर्ध्वं। जीवः। असुः। ११२

© Dharmartha Trust J&K. Digitized by eGangotri

नः । आ । अगात् । अर्व । प्र । अगा । तत् । तमः । आ । ज्योतिः । एति । अरैक् । पंथां । यातवे । सूर्या

२ य । अगन्म । यत्र । प्रऽतिरंते । आयुः । व्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उ

षसः । विऽभातीः । अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजाऽव

ती । याः । गोऽमतीः । उषसः । सर्वऽवीराः । विऽउच्छंति । दाशुषे । मर्त्याय । वायोःऽइव । सूनृतानां ।

उत्ऽअर्के । ताः । अश्वऽदाः । अश्नवत् । सोमऽसुत्वा । माता । देवानां । अदितेः । अनीकं । यज्ञस्य ।

केतुः । बृहती । वि । भाहि । प्रशस्तिऽकृत् । ब्रह्मणे । नः । वि । उच्छ । आ । नः । जने । जनय । विश्वऽवारे ।

यत् । चित्रं । अप्नः । उषसः । वहंति । ईजानाय । शशमानाय । भद्रं । ७ । ४ । इमाः । रुद्राय । तवसे ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. कपर्दिने।क्षयत्ऽवीराय।प्र।भरामहे।मतीः।यथा।शं।असत्।द्विऽपदे।चतुःऽपदे।विश्वं।पुष्टं।
३३४ ग्रामे।अस्मिन्।अनातुरं।मृळ।नः।रुद्र।उत।नः।मयः।कृधि।क्षयत्ऽवीराय।नमसा।वि
धेम।ते।यत्।शं।च।योः।च।मनुः।आऽयेजे।पिता।तत्।अश्याम।तव।रुद्र।प्रऽनीतिषु।अश्या
114 म।ते।सुऽमतिं।देवऽयज्यया।क्षयत्ऽवीरस्य।तव।रुद्र।मीढ्वः।सुम्नऽयन्।इत्।विशः।अस्माकं।
आ।चर।अरिष्टऽवीराः।जुहवाम।ते।हविः।त्वेषं।वयं।रुद्रं।यज्ञऽसाधं।वंकुं।कविं।अवसे।नि।
ह्वयामहे।आरे।अस्मत्।दैव्यं।हेळः।अस्यतु।सुऽमतिं।इत्।वयं।अस्य।आ।वृणीमहे।दिवः।व
राहं।अरुषं।कपर्दिनं।त्वेषं।रूपं।नमसा।नि।ह्वयामहे।हस्ते।बिभ्रत्।भेषजा।वार्याणि।शर्म। ३३४

© Dharmartha Trust J&K. Digitized by eGangotri

वर्म। छर्दिः। अस्मभ्यं। यंसत्॥ ५॥ इदं। पित्रे। मरुतां। उच्यते। वचः। स्वादोः। स्वादीयः। रुद्राय।
वर्धनं। रास्व। च। नः। अमृत। मर्तऽभोजनं। त्मने। तोकाय। तनयाय। मृळ। मा। नः। महान्तं। उ
त। मा। नः। अर्भकं। मा। नः। उक्षन्तं। उत। मा। नः। उक्षितं। मा। नः। वधीः। पितरं। मा। उत। मातरं।
मा। नः। प्रियाः। तन्वः। रुद्र। रिरिषः। मा। नः। तोके। तनये। मा। नः। आयौ। मा। नः। गोषु। मा। नः।
अश्वेषु। रिरिषः। वीरान्। मा। नः। रुद्र। भामितः। वधीः। हविष्मन्तः। सदं। इत्। त्वा। हवामहे। उप।
ते। स्तोमान्। पशुपाःऽइव। आ। अकरं। रास्व। पितः। मरुतां। सुम्नं। अस्मे इति। भद्रा। हि। ते। सु
ऽमतिः। मृळयत्ऽतमा। अथ। वयं। अवः। इत्। ते। वृणीमहे। आरे। ते। गोऽघ्नं। उत। पुरुषऽघ्नं। क्ष

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ऋ॰ यत्ऽवीर। सुम्नं। अस्मे इति। ते। अस्तु। मृळ। च। नः। अधि। च। ब्रूहि। देव। अध। च। नः। शर्म।
११५ 115 यच्छ। द्विऽबर्हाः। अवोचाम। नमः। अस्मै। अवस्यवः। शृणोतु। नः। हवं। रुद्रः। मरुत्वान्।१०।
।११। चित्रं। देवानां। उत्। अगात्। अनीकं। चक्षुः। मित्रस्य। वरुणस्य। अग्नेः। आ। अप्राः।
द्यावापृथिवी इति। अंतरिक्षं। सूर्यः। आत्मा। जगतः। तस्थुषः। च। सूर्यः। देवीं। उषसं। रोचमा
नां। मर्यः। न। योषां। अभि। एति। पश्चात्। यत्र। नरः। देवऽयंतः। युगानि। विऽतन्वते। प्रति। भ
द्राय। भद्रं। भद्राः। अश्वाः। हरितः। सूर्यस्य। चित्राः। एतऽग्वाः। अनुऽमाद्यासः। नमस्यंतः।
दिवः। आ। पृष्ठं। अस्थुः। परि। द्यावापृथिवी इति। यंति। सद्यः। तत्। सूर्यस्य। देवऽत्वं। तत्। महि ११५

© Dharmartha Trust J&K. Digitized by eGangotri

ऽत्वं।मध्या।कर्तोः।विऽततं।सं।जभार।यदा।इत्।अयुक्त।हरितः।सधऽस्थात्।आत्।रात्री।वा
सः।तनुते।सिमस्मै।तत्।मित्रस्य।वरुणस्य।अभिऽचक्षे।सूर्यः।रूपं।कृणुते।द्योः।उपऽस्थे।
अनंतं।अन्यत्।रुशत्।अस्य।पाजः।कृष्णं।अन्यत्।हरितः।सं।भरंति।अद्य।देवाः।उत्ऽइता।
सूर्यस्य।निः।अंहसः।पिपृत।निः।अवद्यात्।६।।७।।नासत्याभ्यां।बर्हिःऽइव।प्र।वृंजे।स्तोमा
न्।इयर्मि।अभ्रियाऽइव।वातः।यौ।अर्भगाय।विऽमदाय।जायां।सेनाऽजुवा।निऽऊहतुः।र
थेन।वीळुपत्मऽभिः।आशुहेमऽभिः।वा।देवानां।वा।जूतिऽभिः।शाशदाना।तत्।रासभः।नास
त्या।सहस्रं।आजा।यमस्य।प्रऽधने।जिगाय।तुग्रः।ह।भुज्युं।अश्विना।उदऽमेघे।रयिं।न।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. कः। चित्। ममृवान्। अवं। अहाः। तं। ऊहथुः। नौभिः। आत्मन्ऽवतीभिः। अंतरिक्षप्रुत्ऽभिः। अपऽउ

११६ दकाभिः। तिस्रः। क्षपः। त्रिः। अहा। अतिव्रजत्ऽभिः। नासत्या। भुज्युं। ऊहथुः। पतंगैः। समुद्रस्य। ध

दू न्वन्। आर्द्रस्य। पारे। त्रिऽभिः। रथैः। शतपत्ऽभिः। षट्ऽअश्वैः। अनारंभणे। तत्। अवीरयेथां। अना

116 स्थाने। अग्रभणे। समुद्रे। यत्। अश्विनौ। ऊहथुः। भुज्युं। अस्तं। शतऽअरित्रां। नावं। आतस्थिऽवांसं।

॥५॥ यं। अश्विना। ददथुः। श्वेतं। अश्वं। अघऽअश्वाय। शश्वत्। इत्। स्वस्ति। तत्। वां। दात्रं। महि। कीर्ते

न्यं। भूत्। पैद्वः। वाजी। सदं। इत्। हव्यः। अर्यः। युवं। नरा। स्तुवते। पज्रियाय। कक्षीवते। अरदतं। पुरंऽ

धिं। कारोतरात्। शफात्। अश्वस्य। वृष्णः। शतं। कुंभान्। असिंचतं। सुरायाः। हिमेन। अग्निं। घ्रंसं। ११६

© Dharmartha Trust J&K. Digitized by eGangotri

अवारयेथां। पितुऽमतीं। ऊर्जं। अस्मै। अधत्तं। ऋबीसे। अत्रिं। अश्विना। अवऽनीतं। उत्। निन्यथुः। सर्वऽग
णं। स्वस्ति। परा। अवतं। नासत्या। अनु। देथां। उच्चाऽबुध्नं। चक्रथुः। जिह्मऽबारं। क्षरन्। आपः। न। पायना
या। राये। सहस्राय। तृष्यते। गोतमस्य। जुजुरुषः। नासत्या। उत। वव्रिं। प्र। अमुंचतं। द्रापिंऽइव। च्यवा
नात्। प्र। अतिरतं। जहितस्य। आयुः। दस्रा। आत्। इत्। पतिं। अकृणुतं। कनीनां। ता। नरा। वां। नरा। शं
स्यं। राध्यं। च। अभिष्टिऽमत्। नासत्या। वरूथं। यत्। विद्वांसा। निधिंऽइव। अपऽगूळ्हं। उत्। दर्शतात्। ऊ
पथुः। वंदनाय। ०। सनये। दंसः। उग्रं। आविः। कृणोमि। तन्यतुः। न। वृष्टिं। दध्यङ्। ह। यत्। मधु।
आथर्वणः। वां। अश्वस्य। शीर्ष्णा। प्र। यत्। ईं। उवाच। अजोहवीत्। नासत्या। करा। वां। महे। याम

© Dharmartha Trust J&K. Digitized by eGangotri

प.न. त्रा। पुरुऽभुजा। पुरंऽधिः। श्रुतं। तत्। ना। शासुःऽइव। वध्रिऽमत्याः। हिरण्यऽहस्तं। अश्विनौ। अदत्तं। आसनः। र
३३७ कस्य। वर्तिकां। अभीके। युवं। नरा। नासत्या। अमुमुक्तं। वृकोऽइति। कविं। पुरुऽभुजा। युवं। ह। कृप
117 माणं। अकृणुतं। विऽचक्षे। चरित्रं। हि। वेःऽइव। अच्छेदि। पर्णं। आजा। खेलस्य। परिऽतक्म्यायां। स
द्यः। जंघां। आयसीं। विश्पलायै। धने। हिते। सर्त्तवे। प्रति। अधत्तं॥१०॥ शतं। मेषान्। वृक्ये। चक्षदा
नं। ऋज्रऽअश्वं। तं। पिता। अंधं। चकार। तस्मै। अक्षी इति। नासत्या। विऽचक्षे। आ। अधत्तं। दस्रा। भि
षजौ। अनर्वन्। आ। वां। रथं। दुहिता। सूर्यस्य। कार्ष्मऽइव। अतिष्ठत्। अर्वता। जयंती। विश्वे। देवाः।
अनु। अमन्यंत। हृत्ऽभिः। सं। ऊं इति। श्रिया। नासत्या। सचेथे इति। यत्। अयातं। दिवःऽदासाय। वर्तिः। ३३७

© Dharmartha Trust J&K. Digitized by eGangotri

भरत्ऽवाजाय । अश्विना । हयंता । रेवत् । उवाह । सचनः । रथः । वां । वृषभः । च । शिंशुमारः । च ।
युक्ता । रयिं । सुऽक्षत्रं । सुऽअपत्यं । आयुः । सुऽवीर्यं । नासत्या । वहंता । आ । जन्हावीं । सऽमनसा
उप । वाजैः । त्रिः । अन्हः । भागं । दधतीं । अयातं । परिऽविष्टं । जाहुषं । विश्वतः । सीं । सुऽगेभिः । न
क्तं । ऊहथुः । रजःऽभिः । विऽभिंदुना । नासत्या । रथेन । वि । पर्वतान् । अजरयू इति । अयातं ॥ १३ ॥
एकस्याः । वस्तोः । अवतं । रणाय । वशं । अश्विना । सनये । सहस्रा । निः । अहतं । दुच्छुनाः । इंद्र
वंता । पृथुऽश्रवसः । वृषणौ । अरातीः । शरस्य । चित् । आर्चत्ऽकस्य । अवतात् । आ । नीचात् ।
उच्चा । चक्रथुः । पातवे । वारिति वाः । शयवे । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यं । पिप्य

© Dharmartha Trust J&K. Digitized by eGangotri

प.म. थुः । गां । अवस्यते । स्तुवते । कृष्णियाय । ऋजुऽयते । नासत्या । शचीभिः । पशुं । न । नष्टंऽइव । दर्शना
१३८ य । विष्णाप्वं । ददथुः । विश्वकाय । दश । रात्रीः । अशिवेन । नव । द्यून् । अवऽनद्धं । श्नथितं । अपऽसु ।
अंतरिति । विऽप्रुतं । रेभं । उदनि । प्रऽवृक्तं । उत् । निन्यथुः । सोमंऽइव । स्रुवेण । प्र । वां । दंसांसि । अश्वि
118 नौ । अवोचं । अस्य । पतिः । स्यां । सुऽगवः । सुऽवीरः । उत । पश्यन् । अश्नुवन् । दीर्घं । आयुः । अस्तंऽइव ।
इत् । जरिमाणं । जगम्यां ॥ २ ॥ मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते ।
वां । बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातं । नासत्या । उप । वाजैः । यः । वां । अश्विना । मनसः ।
जवीयान् । रथः । सुऽअश्वः । विशः । आऽजिगाति । येन । गच्छथः । सुऽकृतः । दुरोणं । तेन । नरा । वर्तिः । १३८

© Dharmartha Trust J&K. Digitized by eGangotri

अस्मभ्यं। यातं। ऋषिं। नरौ। अंहसः। पांचऽजन्यं। ऋबीसात्। अत्रिं। मुंचथः। गणेन। मिनंतां। द
स्योः। अशिवस्य। मायाः। अनुऽपूर्वं। वृषणा। चोदयंता। अश्वं। न। गूढं। अश्विना। दुःऽएवैः।
ऋषिं। नरा। वृषणा। रेभं। अपऽसु। सं। तं। रिणीथः। विऽप्रुतं। दंसःऽभिः। न। वां। जूर्यंति। पूर्व्या। कृ
तानि। सुसुप्वांसं। न। निःऽऋतेः। उपऽस्थे। सूर्यं। न। दस्रा। तमसि। क्षियंतं। शुभे। रुक्मं। न। द
र्शतं। निऽखातं। उत्। ऊपथुः। अश्विना। वंदनाय। ॥५॥ पज्रियेण। कक्षीवता। नासत्या। परि
ऽज्मन्। शफात्। अश्वस्य। वाजिनः। जनाय। ०। मधूनां। ०। कृष्णियाय। ०। घोषायै। चित्। पितृऽ
सदे। दुरोणे। पतिं। जूर्यंत्यै। अश्विनौ। अदत्तं। युवं। श्यावाय। रुशतीं। अदत्तं। महः। क्षोणस्य।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प्र. अश्विना। कण्वाय। प्रऽवाच्यं। तत्। वृषणा। कृतं। वां। यत्। नार्सदाय। श्रवः। अधिऽअधत्तं। पुरु। वर्पां

११९ सि। अश्विना। दधाना। नि। पेदवे। ऊहथुः। आशुं। अश्वं। सहस्रऽसां। वाजिनं। अप्रतिऽइतं। अहिऽ

हनं। श्रवस्यं। तरुत्रं। एतानि। वां। श्रवस्या। सुदानूऽइति सुऽदानू। ब्रह्म। आंगूषं। सदनं। रोदस्योः

119 ः। यत्। वां। पज्रासः। अश्विना। हवंते। यातं। इषा। च। विदुषे। च। वाजं॥१४॥ सूनोः। मानेन। अश्वि

ना। गृणाना। वाजं। विप्राय। भुरणा। रदंता। अगस्त्ये। ब्रह्मणा। वरधाना। सं। विश्पलां। नासत्या।

अरिणीतं। कुह। यांता। सुऽस्तुतिं। काव्यस्य। दिवः। नपाता। वृषणा। शयुऽत्रा। हिरण्यस्यऽइव। क

लशं। निऽखातं। उत्। ऊपथुः। दशमे। अश्विना। अहन्। युवं। च्यवानं। अश्विना। जरंतं। पुनः। राम

११९

© Dharmartha Trust J&K. Digitized by eGangotri

युवानं। चक्रथुः। शचीभिः। युवोः। रथं। दुहिता। सूर्यस्य। सह। श्रिया। नासत्या। अवृणीत। युवं।
तुग्राय। पूर्व्येभिः। एवैः। पुनःऽमन्यौ। अभवतं। युवाना। युवं। भुज्युं। अर्णसः। निः। समुद्रा
त्। विऽभिः। ऊहथुः। ऋज्रेभिः। अश्वैः। अजोहवीत्। अश्विना। तौग्र्यः। वां। प्रऽऊळ्हः। स
मुद्रं। अव्यथिः। जगन्वान्। निः। तं। ऊहथुः। सुऽयुजा। रथेन। मनःऽजवसा। वृषणा। स्वस्ति
॥१५॥ अजोहवीत्। अश्विना। वर्त्तिका। वां। आस्नः। यत्। सीं। अमुंचतं। वृकस्य। वि। जयु
षा। ययथुः। सानु। अद्रेः। जातं। विष्वाचः। अहतं। विषेण। ०। मम्हानं। तमः। प्रऽनीतं।
अशिवेन। पित्रा। आ। अक्षी इति। ऋज्रऽअश्वे। अश्विनौ। अधत्तं। ज्योतिः। अंधाय। चक्र

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ थुः। विऽचक्षे। शुनं। अंधाय। भरं। अह्वयत्। सा। वृकीः। अश्विना। वृषणा। नरा। इति। जारः। कनी
११२॰ नःऽइव। चक्षदानः। ऋज्रऽअश्वः। शतं। एकं। च। मेषान्। मही। वां। ऊतिः। अश्विना। मयःऽभूः।
। उत। स्रामं। धिष्ण्या। सं। रिणीथः। अथ। युवां। इत्। अह्वयत्। पुरंऽधिः। आ। अगच्छतं। सीं।
120 वृषणौ। अवःऽभिः। अधेनुं। दस्रा। स्तर्यं। विऽसक्तां। अपिन्वतं। शयवे। अश्विना। गां। युवं। श
चीभिः। विऽमदाय। जायां। नि। ऊहथुः। पुरुऽमित्रस्य। योषां। १८। यवं। वृकेण। अश्विना। व
पंता। इषं। दुहंता। मनुषाय। दस्रा। अभि। दस्युं। बकुरेण। धमंता। उरु। ज्योतिः। चक्रथुः। आर्या
य। आथर्वणाय। अश्विना। दधीचे। अश्व्यं। शिरः। प्रति। ऐरयतं। सः। वां। मधु। प्र। वोचत्। ऋ ११२

© Dharmartha Trust J&K. Digitized by eGangotri

तःऽयन्। त्वाष्ट्रं। यत्। दस्रौ। अपि। कक्ष्यं। वां। सदा। कवी इति। सुऽमतिं। आ। चके। वां। विश्वाः। धि
यः। अश्विना। प्र। अवतं। मे। अस्मे इति। रयिं। नासत्या। बृहंतं। अपत्यऽसाचं। श्रुत्यं। रराथां।
हिरण्यऽहस्तं। अश्विना। रराणा। पुत्रं। नरा। वध्रिऽमत्याः। अदत्तं। त्रिधा। ह। श्यावं। अश्विना। वि
ऽकस्तं। उत्। जीवसे। ऐरयतं। सुदानू इति सुऽदानू। एतानि। वां। अश्विना। वीर्याणि। प्र। पूर्व्या
णि। आयवः। अवोचन्। ब्रह्म। कृण्वंतः। वृषणा। युवऽभ्यां। सुऽवीरासः। विदथं। आ। वदेम॥१८॥
आ। वां। रथः। अश्विना। श्येनऽपत्वा। सुऽमृळीकः। स्वऽवान्। यातु। अर्वाङ्। यः। मर्त्यस्य। मन
सः। जवीयान्। त्रिऽवंधुरः। वृषणा। वातऽरंहाः। त्रिऽवंधुरेण। त्रिऽवृता। रथेन। त्रिऽचक्रेण।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰८ सुऽवृतां। आ। यातं। अर्वाक्। पिन्वतं। गाः। जिन्वतं। अर्वतः। नः। वर्द्धयतं। अश्विना। वीरं। अ
३२१ स्मे इति। प्रवत्ऽयामना। सुऽवृता। रथेन। दस्रौ। इमं। शृणुतं। श्लोकं। अद्रेः। किं। अंग। वां। प्रति।
अवर्तिं। गमिष्ठा। आहुः। विप्रासः। अश्विना। पुराऽजाः। आ। वां। श्येनासः। अश्विना। वहंतु।
121 रथे। युक्तासः। आशवः। पतंगाः। ये। अप्ऽतुरः। दिव्यासः। न। गृध्राः। अभि। प्रयः। नास
त्या। वहंति। ०। युवतिः। तिष्ठत्। अत्र। जुष्टी। नरा। दुहिता। सूर्यस्य। परि। वां। अश्वाः। वपु
षः। पतंगाः। वयः। वहंतु। अरुषाः। अभीके॥ १८॥ उत्। वंदनं। ऐरतं। दंसनाभिः। उत्। रे
भं। दस्रा। वृषणा। शचीभिः। निः। तौग्र्यं। पारयथः। समुद्रात्। पुनरिति। च्यवानं। च १२१

© Dharmartha Trust J&K. Digitized by eGangotri

कृथुः। युवानं। युवं। अत्रये। अवऽनीताय। तप्तं। ऊर्जं। ओमानं। अश्विनौ। अधत्तं। युवं। क
ण्वाय। अपिऽरिप्ताय। चक्षुः। प्रति। अधत्तं। सुऽस्तुतिं। जुजुषाणा। युवं। धेनुं। शयवे। नाधि
ताय। अपिन्वतं। अश्विना। पूर्व्याय। अमुंचतं। वर्तिकां। अंहसः। निः। प्रति। जंघां। विश्पला
याः। अधत्तं। युवं। श्वेतं। पेदवे। इंद्रऽजूतं। अहिऽहनं। अश्विना। अदत्तं। अश्वं। जोहूत्रं। अर्यः। अ
भिऽभूतिं। उग्रं। सहस्रऽसां। वृषणं। वीडुऽअंगं। ता। वां। नरा। सु। अवसे। सुऽजाता। हवामहे।
अश्विना। नाधमानाः। आ। नः। उप। वसुऽमता। रथेन। गिरः। जुषाणा। सुविताय। यातं।
आ। श्येनस्य। जवसा। नूतनेन। अस्मे इति। यातं। नासत्या। सऽजोषाः। हवे। हि। वां। अश्वि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प्र॰ नारातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥ ९ ॥ पुरुऽमायं । मनःऽजुवं । जीरऽअश्वं ।
३२२ यज्ञियं । जीवसे । हुवे । सहस्रऽकेतुं । वनिनं । शतत्ऽवसुं । श्रुष्टीऽवानं । वरिवःऽधां । अभि । प्रयः ।
122 ऊर्ध्वा । धीतिः । प्रति । अस्य । प्रऽयामनि । अधायि । शस्मन् । सं । अयंत । आ । दिशः । स्वदामि ।
घर्मं । प्रति । यंति । ऊतयः । आ । वां । ऊर्जानी । रथं । अश्विना । अरुहत् । सं । यत् । मिथः । पस्पृधा
नासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे । युवोः । अह । प्रवणे । चेकिते । रथः ।
यत् । अश्विना । वथः । हा । सूरिं । आ । वरं । युवं । भुज्युं । भुरमाणं । विऽभिः । गतं । स्वयुक्तिऽभिः ।
निऽवहंता । पितृऽभ्यः । आ । या । असिष्टं । वर्तिः । वृषणा । विऽजेन्यं । दिवःऽदासाय । महि । चेति । १२२

© Dharmartha Trust J&K. Digitized by eGangotri

गुं। आ। वंः। युवोः। अश्विना। वपुषे। युवा। युजं। रथं। वाणी इति। येमतुः। अस्य। शर्ध्यं। आ। वां।
पतिऽत्वं। सख्याय। जग्मुषी। योषा। अवृणीत। जेन्या। युवां। पती इति॥ रणा। युवं। रेभं। परिऽ
सूतेः। उरुष्यथः। हिमेन। घर्मं। परिऽतप्तं। अत्रये। युवं। शयोः। अवसं। पिप्यथुः। गवि। प्र। दी
र्घेण। वंदनः। तारि। आयुषा॥ युवं। वंदनं। निःऽऋतं। जरण्यया। रथं। न। दस्रा। करणा। सं।
इन्वथः। क्षेत्रात्। आ। विप्रं। जनथः। विपन्यया। प्र। वां। अत्र। विधते। दंसना। भुवत्॥ अगं
तं। कृपमाणं। पराऽवति। पितुः। स्वस्य। त्यजसा। निऽबाधितं। स्वःऽवतीः। इतः। ऊती। युवोः।
अहन्। चित्राः। अभीके। अभवन्। अभिष्टयः॥ उत। स्या। वां। मधुऽमत्। मक्षिका। अरपत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ मदे।सोमस्य।औशिजः।हुवन्यति।युवं।दधीचः।मनः।आ।विवासथः।अथ।शिरः।प्रति।
१२३ वां।अश्व्यं।वदत्।युवं।पेद्वे।पुरुऽवारं।अश्विना।स्पृधां।श्वेतं।तरुतारं।दुवस्यथः।शर्यैः।
अभिऽद्युं।पृतनासु।दुस्तरं।चर्कृत्यं।इन्द्रंऽइव।चर्षणिऽसहं॥२२॥ का।राधत्।होत्रा।अश्विना।
123 वां।कः।वां।जोषे।उभयोः।कथा।विधाति।अप्रऽचेताः।विद्वांसौ।इत्।दुरः।पृच्छेत्।अविद्वान्।
इत्था।अपरः।अचेताः।नु।चित्।नु।मर्त्तः।अक्रौ।ता।विद्वांसा।हवामहे।वां।ता।नः।विद्वांसा।म
न्म।वोचेतं।अद्य।प्र।आर्चत्।दयमानः।युवाकुः।विऽपृच्छामि।पाक्या।न।देवान्।वषट्ऽकृत
स्य।अद्भुतस्य।दस्रा।पातं।च।सह्यसः।युवं।च।रभ्यसः।नः।प्र।या।घोषे।भृगवाणे।न।शोभे। १२३

© Dharmartha Trust J&K. Digitized by eGangotri

यया। वा। चा। यजंति। पञ्जिष्ठः। यां। प्र। इषः। युः। न। विद्वान्। २२। श्रुतं। गायत्रं। तर्कवानस्य। अहं।
चित्। हि। रिरेभ। आश्विना। यां। आ। अक्षी इति। शुभः। पती इति। दन्ना। युवं। हि। अस्तं। महः। रन्।
युवं। वा। यत्। निःऽअततंसतं। ना। नः। वस्य इति। सुऽगोपा। स्यातं। पातं। नः। वृकात्। अघऽयोः। मा।
कस्मै। धातं। अभि। अमित्रिणे। नः। मा। अकुत्र। नः। गृहेभ्यः। धेनवः। गुः। स्तनऽभुजः। अशिश्वीः।
दुहीयन्। मित्रऽधितये। युवाकु। राये। च। नः। मिमीतं। वाजऽवत्यै। इषे। च। नः। मिमीतं। धेनुऽमत्यै।
अश्विनोः। असनि। रथं। अनश्वं। वाजिनीऽवतोः। तेन। अहं। भूरि। चाकन। अयं। सम्ऽमह। मा। तनु। उ।
स्यात्। जनान्। अनु। सोमऽपेयं। सुऽरथः। रयः। अध। स्वप्नस्य। निः। विदे। अभुंजतः। च। रेवतः। उभा।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प्र॰ ता। बस्त्रिः। नुऽश्यतः॥ रक्षा। कृत्वा। इत्था। नूनं। पात्रं। देवऽयतां। भरन्ता। गिरः। आंगिरसां। तुरण्यन्। आत्राय

१२४ ता। आ नर्द्। विशः। आ। हर्म्यस्य। उरु। ऋंऽस्तले। अध्वरे। यजत्रः। स्तंभीता। हि। थां। स्वः। धरुणं। त्रुषाय्। ला।

124 ऋभुः। वाजाय। द्रविणं। नरः। गोः। अनु। स्वऽजां। मुहिषः। चक्षतुः। ग्रां। मेनां। अश्वस्य। परि। मातरं। गो

ः। नक्षत्। हवैं। अरुणीः। पूर्व्यं। राट्। तुरः। विशं। आंगिरसां। अनु। घून्। नक्षत्। वज्रं। निऽयुतं। तस्तंभ

त्। द्यां। चतुःऽपदे। नर्याय। द्विऽपादे। अस्य। मदे। स्वर्यां। दाः। ऋताय। अपिऽवृतं। उस्त्रियाणां। अनी

कं। यत्। हि। प्रऽसर्गे। त्रिऽककुप्। निऽवर्तत्। अप। द्रुहः। मानुषस्य। दुरः। वरिलिवः। नुभ्यं। पयः। यत्

पितरौ। अनीतां। राधः। सुऽरेतः। तुरणे। भुरण्यू इति। शुचि। यत्। ते। रेक्णः। आ। अयजंत। सबः। १२४

© Dharmartha Trust J&K. Digitized by eGangotri

दुघायाः। पयः। उस्रियायाः॥ २४॥ अध। म्रा। जज्ञे। तरणिः। मममन्तु। प्र। रोचि। अस्याः। उषसः। न। सूरः।
इन्दुः। येभिः। आ। स्व ऽ इद्धहव्यैः। स्रुवेण। सिंचन्। अरणा। अभि। [illegible] धाम। सु ऽ इध्मा। यत्। वनः
धितिः। अपस्यात्। सूरः। अध्वरे। परि। रोधना। गोः। यत्। ह। प्र ऽ भासि। कृत्व्यान्। अनु। सून्। अन
विशे। पशु ऽ इषे। तुराय॥ अत्र। महः। दिवः। आदः। हरी इति। इह। द्युम्न ऽ सहं। अभि। योधानः। उत्सं।
हरिं। यत्। ते। मंदिनं। धुक्षन्। वृधे। गो ऽ रभसं। अद्रिऽभिः। वाता। प्यं। त्वं। आयसं। प्रति। वर्तयः। गोः
। दिवः। अश्मानं। उप ऽ नीतं। ऋभ्वा। कुत्साय। यत्र। पुरु ऽ हूत। वन्वन्। शुष्णं। अनंतैः। परि ऽ या
सि। वधैः। पुरा। यत्। सूरः। तमसः। अपि ऽ इतेः। तं। अद्रि ऽ वः। फलि ऽ गं। हेतिं। अस्य। शुष्णस्य। चि

© Dharmartha Trust J&K. Digitized by eGangotri

पु.त्र. न । परिऽहृतं । यत्र । ओजः । दिवः । परि । सुऽग्रथितं । तत् । आ । अदरिऽस्वदः ॥ २५ ॥ अनु । त्वा । मही इति ।
१२५ पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदतां । इंद्र । कर्मन् । त्वं । वृत्रं । आऽशयानं । सिरासु । महः । व
125 ज्रेण । सिस्वपः । वराहुं ॥ त्वं । इंद्र । नर्यः । यान् । अवः । नृन् । तिष्ठ । वातस्य । सुऽयुजः । वहिष्ठान् । यं । ते ।
काव्यः । उशना । मंदिनं । दात् । वृत्रऽहनं । पार्यं । ततक्ष । वज्रं ॥ त्वं । सूरः । हरितः । रमयः । नृन् । भरत् । चक्रं
एतशः । न । अयं । इंद्र । प्र । अस्य । पारं । नवतिं । नाव्यानां । अपि । कर्त्तं । अवर्त्तयः । अयज्यून् ॥ त्वं । नः । अ
स्याः । इंद्र । दुःऽहनायाः । पाहि । वज्रिऽवः । दुःऽइतात् । अभीके । प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्या
न् । इषे । यंधि । श्रवसे । सूनृतायै ॥ मा । सा । ते । अस्मत् । सुऽमतिः । वि । दसत् । वाजऽप्रमहः । सं । इषः । १२५

© Dharmartha Trust J&K. Digitized by eGangotri

126

यरंत। आ। नः। भज। मघऽवन्। गोषु। अर्यः। मंहिष्ठाः। ते। सधऽमादः। स्याम॥ २८॥ इति प्रथमाष्टके

अष्टमोध्यायः॥ ॥श्रीकृष्णार्पणमस्तु॥ ॥संवत् [illegible]॥ प्लवनामसंवत्सरे॥ शके १७॥ ८२॥

दक्षिणायने॥ श्रावणेमासे शुक्लपक्षे तृतीयायां तिथौ गुरुवासरे॥ ॥ ॥ ॥ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

२ प

१११०

© Dharmartha Trust J&K. Digitized by eGangotri

१·द्वि श्रीगणेशायनमः॥गोपाकृष्णायनमः॥हरिःॐ॥प्रवोवैश्वदेवमायोविराड्रूपंपृथुःसप्तोनो
१ षस्यंत्रुबाउष्ठंतीप्रानारलंसप्तस्वनयस्यदानस्तुतिरुपजगत्यांवमंदानित्रिकक्षीवान्दान
तुष्टःपंचभिर्भावयव्यंनुष्टाबांत्येअनुष्टुभौभावयव्यरोमशयोर्दंपत्योःसंवादोग्निमेकादश
परुच्छेपौर्दैवोदासिराग्नेयंतुपारुच्छेपंसर्वत्यष्टंनत्राधृतिःषष्ठ्यैयंजायतामष्टौयंत्वमेकादशष
ष्ठ्यैंद्वीप्रप्रावोतिशक्वर्यावःष्टिरंत्यंद्द्याहिदशंत्यात्रिष्टुबिंद्रायसप्तत्वपावयंषड्नुवंतमैंद्रा
पार्वतोद्वैंचैतुभेसप्तादौत्रिष्टुप्तिनिस्रोनुष्टुभोगायत्रीधृतिरष्टिरात्वाषड्गायत्र्यंसंत्याष्टिःस्तीर्ण
नवंचतुर्थ्योघाःपंचैंद्राश्वौपांत्येअष्टौप्रसुसप्तमैत्रावरुणंत्वंत्येतिलिंगोक्तदेवतंअंत्यात्रिष्टुप्॥ १

© Dharmartha Trust J&K. Digitized by eGangotri

हरिः ॐ ॥ प्र । वः । पांतं । रघुऽमन्यवः । अंधः । यज्ञं । रुद्राय । मीळ्हुषे । भरध्वं । दिवः । अस्तोषि । असु
रस्य । वीरैः । इषुध्याऽइव । मरुतः । रोदस्योः । पत्नीऽइव । पूर्वऽहूतिं । ववृधध्यै । उषसानक्ता । पुरुधा ।
विदाने इति । स्तरीः । न । अत्कं । विऽउतं । वसाना । सूर्यस्य । श्रिया । सुऽदृशी । हिरण्यैः । ममत्तु । नः
। परिऽज्मा । वसर्हा । ममत्तु । वातः । अपां । वृषण्ऽवान् । शिशीतं । इंद्रापर्वता । युवं । नः । तत् । नः ।
विश्वे । वरिवस्यंतु । देवाः । उत । त्या । मे । यशसा । श्वैतनायै । व्यंता । पांता । औशिजः । हुवध्यै । प्र
वः । नपातं । अपां । कृणुध्वं । प्र । मातरा । रास्पिनस्य । आयोः । आ । वः । रुवण्युं । औशिजः । हुवध्यै
। घोषाऽइव । शंसं । अर्जुनस्य । नंशे । प्र । वः । पूष्णे । दावने । आ । अछ । वोचेय । वसुऽतातिं । अग्नेः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰छि॰ ॥१॥ श्रुतं। मे। मित्रावरुणा। हवा। इमा। उत। श्रुतं। सदने। विश्वतः। सीं। श्रोतु। नः। श्रोतुऽरातिः। सुऽ

२ श्रोतुः। सुऽक्षेत्रा। सिंधुः। अत्ऽभिः। स्तुषे। सा। वां। वरुणा। मित्र। रातिः। गवां। शता। पृक्षऽयामेषु। प

ज्रे। श्रुतऽरथे। प्रियऽरथे। दधानाः। सद्यः। पुष्टिं। निऽरुंधानासः। अग्मन्। अस्य। स्तुषे। महिऽमघ

2 स्य। राधः। सचा। सनेम। नहुषः। सुऽवीराः। जनः। यः। पज्रेभ्यः। वाजिनीऽवान्। अश्वऽवतः। रथिनः।

मह्यं। सूरिः। जनः। यः। मित्रावरुणौ। अभिऽध्रुक्। अपः। न। वां। सुनोति। अक्ष्णयाऽध्रुक्। स्वयं

सः। यक्ष्मं। हृदये। नि। धत्ते। आप। यत्। ईं। होत्राभिः। ऋतऽवा। सः। व्राधतः। नहुषः। दंऽसुजूतः। श

र्धःऽतरः। नरां। गूर्तऽश्रवाः। विसृष्टऽरातिः। याति। बाल्हऽसृत्वा। विश्वासु। पृत्ऽसु। सदां। इत्। शूरः। २

© Dharmartha Trust J&K. Digitized by eGangotri

॥ २॥ अध। ग्मंत। नहुषः। हवं। सूरेः। श्रोत। राजानः। अमृतस्य। मंद्राः। नभःऽजुवः। यत्। निरवस्य।
राधः। प्रऽशस्तये। महिना। रथऽवते। एतं। शर्धं। धाम। यस्य। सूरेः। इति। अवोचन्। दशऽतयस्य।
नंशे। द्युम्नानि। येषु। वसुऽतातिः। ररन्। विश्वे। सन्वंतु। प्रऽभृथेषु। वाजं। मंदामहे। दशऽतयस्य।
धासेः। द्विः। यत्। पंच। बिभ्रतः। यंति। अन्ना। किं। इष्टऽअश्वः। इष्टऽरश्मिः। एते। ईशानासः। नरु
षः। ऋंजते। नृऽत्रा। हिरण्यऽकर्णं। मणिऽग्रीवं। अर्णः। ०। अर्यः। गिरः। सद्यः। आ। जग्मुषीः। आ। उस्रा
ः। वाकं। तु। उभयेषु। अस्मे इति। चत्वारः। मा। मशर्शारस्य। शिश्वः। त्रयः। राज्ञः। आयवसस्य।
जिष्णोः। रथः। वां। मित्रावरुणा। दीर्घऽअप्साः। स्यूमऽगभस्तिः। सूरः। न। अद्यौत्। ॥ ३॥ पृथुः। र

© Dharmartha Trust J&K. Digitized by eGangotri

१·दिः थः। दक्षिणायाः। अयोजि। आ। एनं। देवासः। अमृतासः। अस्थुः। कृष्णात्। उत्। अस्थात्। अर्या

२ विऽहायाः। चिकित्सन्ती। मानुषाय। क्षयाय। पूर्वा। विश्वस्मात्। भुवनात्। अबोधि। जयन्ती। वा

जं। बृहती। सनुत्री। उच्चा। वि। अख्यत्। युवतिः। पुनःऽभूः। आ। उषाः। अगन्। प्रथमा। पूर्वऽहूतौ।

3 यत्। अद्य। भागं। विऽभजासि। नृऽभ्यः। उषः। देवि। मर्त्यऽत्रा। सुऽजाते। देवः। नः। अत्र। सविता।

दमूनाः। अनागसः। वोचति। सूर्याय। गृहंऽगृहं। अहना। याति। अच्छ। दिवेऽदिवे। अधि। नाम।

दधाना। सिसासन्ती। द्योतना। शश्वत्। आ। अगात्। अग्रंऽअग्रं। इत्। भजते। वसूनां। भगस्य।

स्वसा। वरुणस्य। जामिः। उषः। सूनृते। प्रथमा। जरस्व। पश्चा। सः। दघ्याः। यः। अघस्य। धाता। २

© Dharmartha Trust J&K. Digitized by eGangotri

जयेम। तं। दक्षिणया। रथेन॥ २॥ उत्। ईरतां। सूनृताः। उत्। पुरंऽधीः। उत्। अग्नयः। शुशुचानासः।
अस्थुः। स्पार्हा। वसूनि। तमसा। अपऽगूळ्हा। आविः। कृण्वंति। उषसः। विऽभातीः। अप। अन्य
त्। एति। अभि। अन्यत्। एति। विषुरूपे इति विषुऽरूपे। अहनी इति। सं। चरेते इति। परिऽक्षितोः। त
मः। अन्या। गुहा। अकः। अद्यौत्। उषाः। शोशुचता। रथेन। सऽदृशीः। अद्य। सऽदृशीः। इत्। ऊं इति। श्वः।
दीर्घं। सचंते। वरुणस्य। धाम। अनवद्याः। त्रिंशतं। योजनानि। एकाऽएका। क्रतुं। परि। यंति। स
द्यः। जानती। अह्नः। प्रथमस्य। नाम। शुक्रा। कृष्णात्। अजनिष्ट। श्वितीची। ऋतस्य। योषा। न। मि
नाति। धाम। अहःऽअहः। निःऽकृतं। आऽचरंती। कन्याऽइव। तन्वा। शाशदाना। एषि। देवि। देवं। इ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ह्नि॰ यक्षमाणं। संऽस्मयमाना। युवतिः। पुरस्तात्। आविः। वक्षांसि। कृणुषे। विऽभाती॥१०॥ सुऽसंका

५ शा। मातृमृष्टाऽइव। योषा। आविः। तन्वं। कृणुषे। दृशे। कं। भद्रा। त्वं। उषः। विऽतरं। विऽउछ। न। तत्।

ते। अन्याः। उषसः। नशंत। अश्वऽवतीः। गोऽमतीः। विश्वऽवाराः। यतमानाः। रश्मिऽभिः। सूर्यस्य।

परा। च। यंति। पुनः। आ। च। यंति। भद्रा। नाम। वहमानाः। उषसः। ऋतस्य। रश्मिं। अनुऽयछमाना।

भद्रंऽभद्रं। क्रतुं। अस्मासु। धेहि। उषः। नः। अद्य। सुऽहवा। विऽउछ। अस्मासु। रायः। मघवत्ऽसु। च।

स्युरिति स्युः॥१३॥ उषाः। उछंती। संऽइधाने। अग्नौ। उत्ऽयन्। सूर्यः। उर्विया। ज्योतिः। अश्रेत्॥०॥ नु।

पा। अर्थं। प्र। असावीत्। द्विऽपत्। चतुःऽपत्। इत्यै॥०॥ आऽयतीनां॥०॥ अधैत्॥०॥ ज्योतिः। वसाना। सऽमनाः ५

© Dharmartha Trust J&K. Digitized by eGangotri

पुरस्तात्। ऋतस्य। पंथां। अनु। एति। साधु। प्रजानतीऽइव। न। दिशः। मिनाति। उपोइति। अदर्शि
शुंध्युवः। न। वक्षः। नोधाःऽइव। आविः। अकृत। प्रियाणि। अद्मऽसत्। न। ससतः। बोधयंती। श
श्वत्तमा। आ। अगात्। पुनरिति। आऽईयुषीणां। पूर्वा। अर्धे। रजसः। अप्त्यस्य। गवां। जनित्री। अकृ
त। प्र। केतुं। वि। ऊंइति। प्रथते। विऽतरं। वरीयः। आ। उभा। पृणंती। पित्रोः। उपऽस्था॥ ५॥ एव। इत्।
एषा। पुरुऽतमा। दृशे। कं। न। अजामिं। न। परि। वृणक्ति। जामिं। अरेपसा। तन्वा। शाशदाना। न। अ
र्भात्। ईषते। न। महः। विऽभाती। अभ्राताऽइव। पुंसः। एति। प्रतीची। गर्त्तऽआरुगिव। सनये। ध
नानां। जायाऽइव। पत्ये। उशती। सुऽवासाः। उषाः। हस्राऽइव। नि। रिणीते। अप्सः। स्वसा। स्वस्रे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ह्रिं ज्यायस्यै। योनिं। अरैक्। अप। एति। अस्याः। प्रतिचक्ष्याऽइव। विऽउच्छन्ती। रश्मिऽभिः। सूर्यस्य। अं
५ जि। अङ्क्ते। समनगाःऽइव। व्राः। आसां। पूर्वासां। अहःऽसु। स्वसॄणां। अपरा। पूर्वां। अभि। एति।
पश्चात्। ताः। प्रत्नऽवत्। नव्यसीः। नूनं। अस्मे इति। रेवत्। उच्छन्तु। सुऽदिनाः। उषसः। प्र। बोधय।
उषः। पृणतः। मघोनि। अबुध्यमानाः। पणयः। ससन्तु। रेवत्। उच्छ। मघवत्ऽभ्यः। मघोनि। रेवत्।
स्तोत्रे। सूनृते। जारयन्ती॥ ८॥ अव। इयं। अश्वैत्। युवतिः। पुरस्तात्। युङ्क्ते। गवां। अरुणानां। अ
नीकं। वि। नूनं। उच्छात्। असति। प्र। केतुः। गृहंऽगृहं। उप। तिष्ठाते। अग्निः। उत्। ते। वयः। चित्। व
सतेः। अपप्तन्। नरः। च। ये। पितुऽभाजः। विऽउष्टौ। अमा। सते। वहसि। भूरि। वामं। उषः। देवि। ५

© Dharmartha Trust J&K. Digitized by eGangotri

दाशुषे। मसीय। [illegible]। अस्तोढं। स्तोम्याः। ब्रह्मणा। मे। अवीरधध्वं। उशतीः। उषसः। सु
ष्माकं। देवीः। अवसा। सनेम। सहस्रिणं। च। शतिनं। च। वाजं॥ १॥ प्रातरिति। रत्नं। प्रातःऽइत्वा। द
धाति। तं। चिकित्वान्। प्रतिऽगृह्य। नि। धत्ते। तेन। प्रऽजां। वर्धयमानः। आयुः। रायः। पोषेण। सच
ते। सुऽवीरः। सुऽगुः। असत्। सुऽहिरण्यः। सुऽअश्वः। बृहत्। अस्मै। वयः। इंद्रः। दधाति। यः। त्वा। आ
ऽयंतं। वसुना। प्रातःऽइत्वः। मुक्षीजयाऽइव। पदिं। उत्ऽसिनाति। आयं। अद्य। सुऽकृतं। प्रातः। इच्छ
न्। इष्टः। पुत्रं। वसुऽमता। रथेन। अंशोः। सुतं। पायय। मत्सरस्य। क्षयत्ऽवीरं। वर्धय। सूनृताभिः।
उप। क्षरंति। सिंधवः। मयःऽभुवः। ईजानं। च। यक्ष्यमाणं। च। धेनवः। पृणंतं। च। पपुरिं। च। श्रवस्य

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ह्रि॰ वः। घृतस्य। धाराः। उप। यंति। विश्वतः। नाकस्य। पृष्ठे। अधि। तिष्ठति। श्रितः। यः। पृणाति। सः। ह। देवेषु। गच्छति।
६ तस्मै। आपः। घृतं। अर्षंति। सिंधवः। तस्मै। इयं। दक्षिणा। पिन्वते। सदा। दक्षिणाऽवतां। इत्। इमा
नि। चित्रा। दक्षिणाऽवतां। दिवि। सूर्यासः। दक्षिणाऽवंतः। अमृतं। भजंते। दक्षिणाऽवंतः। प्र। तिरंते।
6 आयुः। मा। पृणंतः। दुःऽइतं। एनः। आ। अरन्। मा। जारिषुः। सूरयः। सुऽव्रतासः। अन्यः। तेषां। प
रिऽधिः। अस्तु। कः। चित्। अपृणंतं। अभि। सं। यंतु। शोकाः॥ ३०॥ अमंदान्। स्तोमान्। प्र। भरे।
मनीषा। सिंधौ। अधि। क्षियतः। भाव्यस्य। यः। मे। सहस्रं। अमिमीत। सवान्। अतूर्तः। राजा।
श्रवः। इच्छमानः। शतं। राज्ञः। नाधमानस्य। निष्कान्। शतं। अश्वान्। प्रऽयतान्। सद्यः। आ। अदं। श ६

न

© Dharmartha Trust J&K. Digitized by eGangotri

सहस्रे।

तं।कक्षीवान्।असुरस्य।गोनां।दिवि।श्रवः।अजरं।आ।नतान्।उप।मा।श्यावाः।स्वनयेन।द्
ताः।वधूऽमंतः।दश।रथासः।अस्थुः।षष्टिः।अनु।गव्यं।आ।अगात्।सनत्।कक्षीवान्।अ
भिऽपित्वे।अह्नां।चत्वारिंशत्।दशऽरथस्य।शोणाः।सहस्रस्य।अग्रे।श्रेणिं।नयंति।मदऽच्यु
तः।कृशनऽवतः।अत्यान्।कक्षीवंतः।उत्।अमृक्षंत।पज्राः।पूर्वां।अनु।प्रऽयतिं।आ।ददे।वः।
त्रीन्।युक्तान्।अष्टौ।अरिऽधायसः।गाः।सुऽबंधवः।ये।विश्याःऽइव।व्राः।अनस्वंतः।श्रवः।
ऐषंत।पज्राः।आऽगधिता।परिऽगधिता।या।कशीकाऽइव।जंगहे।ददाति।मह्यं।यादुरी।या
शूनां।भोज्या।शता।उपऽउप।मे।परा।मृश।मा।मे।दभ्राणि।मन्यथाः।सर्वा।अहं।अस्मि।रो

© Dharmartha Trust J&K. Digitized by eGangotri

प·ह्रिः मशा। गंधारीणांऽइवा। अविका॥३३॥ अग्निं। होतारं। मन्ये। दास्वंतं। वसुं। सूनुं। सहसः। जातऽवे
७ दसं। विप्रं। न। जातऽवेदसं। यः। ऊर्ध्वया। सुऽअध्वरः। देवः। देवाच्या। कृपा। घृतस्य। विऽभ्राष्टिं।
अनु। वष्टि। शोचिषा। आऽजुह्वानस्य। सर्पिषः। यजिष्ठं। त्वा। यजमानाः। हुवेम। ज्येष्ठं। अंगिर
सां। विप्र। मन्मऽभिः। विप्रेभिः। शुक्र। मन्मऽभिः। परिज्मानंऽइव। द्यां। होतारं। चर्षणीनां। शोचिः
ऽकेशं। वृषणं। यं। इमाः। विशः। प्र। अवंतु। जूतये। विशः। सः। हि। पुरु। चित्। ओजसा। विरुक्म
ता। दीद्यानः। भवति। दुहंऽतरः। परशुः। न। दुहंऽतरः। विळु। चित्। यस्य। संऽऋतौ। श्रुवत्। वना। इ
व। यत्। स्थिरं। निःऽसहमानः। यमते। न। अयते। धन्वऽसहा। न। अयते। दृळ्हा। चित्। अस्मै। ७

© Dharmartha Trust J&K. Digitized by eGangotri

अनु।कुः। यथा। विदे। नेजिष्ठाभिः। अरणिऽभिः। दाष्टि। अवसे। अग्नये। दाष्टि। अवसे। प्र। यः। पुरू
णि। गाहते। तक्षत्। वनाऽइव। शोचिषा। स्थिरा। चित्। अन्ना। नि। रिणाति। ओजसा। नि। स्थिरा
णि। चित्। ओजसा। तं। अस्य। पृक्षं। उपरासु। धीमहि। नक्तं। यः। सुदर्शऽतरः। दिवाऽतरात्। अप्र
ऽआयुषे। दिवाऽतरात्। आ। तत्। अस्य। आयुः। ग्रभणऽवत्। वीळु। शर्म। न। सूनवे। भक्तं। अभक्तं।
अवः। व्यंतः। अजराः। अग्नयः। व्यंतः। अजराः।।३।। सः। हि। शर्द्धः। न। मारुतं। तुविऽस्वनिः। अप्नस्व
तीषु। उर्वरासु। इष्ठनिः। आर्तनासु। इष्ठनिः। आदत्। हव्यानि। आऽददिः। यज्ञस्य। केतुः। अर्हणा।
अध। स्म। अस्य। हर्षतः। हृषीवतः। विश्वे। जुषंत। पंथां। नरः। शुभे। न। पंथां। हुता। यत्। ईं। कीस्ता

© Dharmartha Trust J&K. Digitized by eGangotri

एषां।

प॰द्वि॰ सः।अभिऽद्यवः।नमस्यंतः।उपऽवोचंत।भृगवः।मथ्नंतः।दाशा।भृगवः।अग्निः।ईशे।वसूनां।शुचि

८ ःयः।धर्णिः।प्रियान्।अपिऽधीन्।वनिषीष्ट।मेधिरः।आ।वनिषीष्ट।मेधिरः।विश्वासां।त्वा।वि

शां।पतिं।हवामहे।सर्वासां।समानं।दंपतिं।भुजे।सत्यऽगिर्वाहसं।भुजे।अतिथिं।मानुषाणां।पि

तुः।न।यस्य।आसया।अमीइति।च।विश्वे।अमृतासः।आ।वयः।हव्या।देवेषु।आ।वयः।त्वं।अ

ग्ने।सहसा।सहन्ऽतमः।शुष्मिन्ऽतमः।जायसे।देवऽतातये।रयिः।न।देवऽतातये।शुष्मिन्ऽत

मः।हि।ते।मदः।द्युम्निन्ऽतमः।उत।क्रतुः।अध।स्म।ते।परि।चरंति।अजर।श्रुष्टीऽवानः।न।अ

जर।प्र।वः।महे।सहसा।सहस्वते।उषःऽबुधे।पशुऽसे।न।अग्नये।स्तोमः।बभूतु।अग्नये।प्रति। ८

© Dharmartha Trust J&K. Digitized by eGangotri

यन्तां।ई।हविष्मान्।विश्वा।सुऽआसा सु।जोगुवे।अग्ने।रेभः।न।जरते।ऋषूणां।जूर्णिः।होता।ऋषूणां
।सः।नः।नेदिष्ठं।ददृशा।नः।आ।भर।अग्ने।देवेभिः।सऽचनाः।सुऽचेतुना।महः।रायः।सुऽचेतुना।
महि।शविष्ठ।नः।कृधि।संऽचक्षे।भुजे।अस्यै।महि।स्तोतृऽभ्यः।मघऽवन्।सुऽवीर्यं।मथीः।उग्रः।न
।शवसा।।१३।।अयं।जायत।मनुषः।धरीमणि।होता।यजिष्ठः।उशिजां।अनु।व्रतं।अग्निः।स्वं।
अनु।व्रतं।विश्वऽश्रुष्टिः।सखिऽयते।रयिःऽइव।श्रवस्यते।अदब्धः।होता।नि।सदत्।इळः।पदे।
परिऽवीतः।इळः।पदे।तं।यज्ञऽसाधं।अपि।वातयामसि।ऋतस्य।पथा।नमसा।हविष्मता।सः
नः।ऊर्जां।उपऽआभृति।अया।कृपा।न।जूर्यति।यं।मातरिश्वा।मनवे।पराऽवतः।देवं।भारिति
देवऽताता।हविष्मता।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰ भाः। पराऽवतः। एवेन। सद्यः। परि। एति। पार्थिवं। मुहुःऽगीः। रेतः। वृषभः। कनिक्रदत्। दधत्। रेतः।
१ कनिक्रदत्। शतं। चक्षाणः। अक्षऽभिः। देवः। वनेषु। तुर्वणिः। सदः। दधानः। उपरेषु। सानुषु। अग्निः।
परेषु। सानुषु। सः। सुऽक्रतुः। पुरःऽहितः। दमेऽदमे। अग्निः। यज्ञस्य। अध्वरस्य। चेतति। क्रत्वा। यज्
9 ञस्य। चेतति। क्रत्वा। वेधाः। इषुऽयते। विश्वा। जातानि। पस्पशे। यतः। घृतऽश्रीः। अतिथिः। अ
जायत। वह्निः। वेधाः। अजायत। क्रत्वा। यत्। अस्य। तविषीषु। पृंचते। अग्नेः। अवेन। मरुतां। न।
भोज्या। इषिराय। न। भोज्या। सः। हि। स्म। दानं। इन्वति। वसूनां। च। मज्मना। सः। नः। त्रासते। दुःऽ
इतात्। अभिऽह्रुतः। शंसात्। अघात्। अभिऽह्रुतः। ॥१४॥ विश्वः। विऽहायाः। अरतिः। वसुः। द १

© Dharmartha Trust J&K. Digitized by eGangotri

ध्ये। हस्त्यो। दक्षिणे। तरणिः। न। शिश्रथत्। श्रवस्यया। न। शिश्रथत्। विश्वस्मै। इत्। इषुध्यते। देवऽत्रा।
हव्यं। आ। ऊहिषे। विश्वस्मै। इत्। सुऽकृते। वारं। ऋण्वति। अग्निः। द्वारा। वि। ऋण्वति। सः। मानुषे।
वृजने। शंऽतमः। हितः। अग्निः। यज्ञेषु। जेन्यः। न। विश्पतिः। प्रियः। यज्ञेषु। विश्पतिः। सः। हव्या। मा
नुषाणां। इळा। कृतानि। पत्यते। ०। वरुणस्य। धूर्तेः। महः। देवस्य। धूर्तेः। अग्निं। होतारं। ईळते। व
सुऽधितिं। प्रियं। चेतिष्ठं। अरतिं। नि। एरिरे। हव्यऽवाहं। नि। एरिरे। विश्वऽआयुं। विश्वऽवेदसं। होता
रं। यजतं। कविं। देवासः। रण्वं। अवसे। वसुऽयवः। गीःऽभिः। रण्वं। वसुऽयवः। १५। यं। त्वां। रथं। इंद्र।
मेधऽसातये। अपाका। सन्तं। इषिर। प्रऽनयसि। प्र। अनवद्य। नयसि। सद्यः। चित्। तं। अभिष्टये।

© Dharmartha Trust J&K. Digitized by eGangotri

प्र.द्विः
३०
10

करः। वशः। च। वाजिनं। सः। अस्माकं। अनवद्य। तूतुजान। वेधसां। इमां। वाचं। न। वेधसां। सः। श्रु
धि। यः। स्म। पृतनासु। कासु। चित्। दक्षाय्यः। इंद्र। भरऽहूतये। नृऽभिः। असि। प्रऽतूर्तये। नृऽभिः।
यः। शूरैः। स्वरिति स्वः। सनिता। यः। विप्रैः। वाजं। तरुता। तं। ईशानासः। इषधंत। वाजिनं। पृक्षं।
अत्यं। न। वाजिनं। दस्मः। हि। स्म। वृषणं। पिन्वसि। त्वचं। कं। चित्। यावीः। अररुं। शूर। मर्त्यं। परि
ऽवृणक्षि। मर्त्यं। इंद्र। उत। तुभ्यं। तत्। दिवे। तत्। रुद्राय। स्वऽयशसे। मित्राय। वोचं। वरुणाय। स
प्रथः। सुऽमृळीकाय। सऽप्रथः। अस्माकं। वः। इंद्रं। उश्मसि। इष्टये। सखायं। विश्वऽआयुं। प्रऽस
हं। युजं। वाजेषु। प्रऽसहं। युजं। अस्माकं। ब्रह्म। ऊतये। अव। पृत्सुषु। कासु। चित्। नहि। त्वा। शत्रुः। १०

© Dharmartha Trust J&K. Digitized by eGangotri

स्तऽरै। स्तरणो। षिःयं। विश्वं। शत्रुं। स्तरणो। षिःयं। नि। सु। नम। अतिःमतिं। कयस्य। चित्। तेजिष्ठाभि

ःअरणिऽभिः। नऊतिऽभिः। उग्राभिः। उग्र। ऊतिऽभिः। नेषि। नः। यथा। पुरा। अनेनाः। शूरा। मन्यसे

। विश्वानि। पूरोः। अप। पर्षि। वह्निः। आसा। वह्निः। नः। अच्छ। ऽधा। प्रानत। वोचेयं। भव्याय। इंद

वे। हव्यः। नाय्यः। इषऽवान्। मन्मारेजति। रक्षःऽहा। मन्मारेजति। स्वयं। सः। अस्मत्। आ। निदः। व

धैः। अजेत। दुःऽमतिं। अव। स्रवेत्। अघऽशंसः। अवऽतरं। अव। क्षुद्रंऽइव। स्रवेत्। वनेम। तत्। हो

त्रया। चित्तं। त्वा। वनेम। रयिं। रयिऽवः। सुऽवीर्यं। रण्वं। संतं। सुऽवीर्यं। दुःऽमन्मानं। सुमंतुःऽभि

ः। आ। ईं। इषा। पृचीमहि। आ। सत्याभिः। इंद्रं। द्युम्नहूतिऽभिः। यजत्रं। द्युम्नहूतिऽभिः। प्रऽप्रा। वः।

© Dharmartha Trust J&K. Digitized by eGangotri

पु·द्वि·
११
अस्मे इति । स्वयशःऽभिः । ऊती । परिऽवर्गे । इंद्रः । दुःऽमतीनां । दरीमन् । दुःऽमतीनां । स्वयं । सा । रिषय
ध्यै । या । नः । उपऽईषे । अत्रैः । हता । ईं । असन् । न । वक्षति । क्षिप्ता । जूर्णिः । न । वक्षति । त्वं । नः । इंद्र । राया ।
परीणसा । याहि । पथा । अनेहसा । पुरः । याहि । अरक्षसा । सचस्व । नः । पराके । आ । सचस्व । अस्तं ।
ईके । आ । पाहि । नः । दूरात् । आरात् । अभिष्टिऽभिः । सदा । पाहि । अभिष्टिऽभिः । ९ । तरूषसा । उग्रं ।
चित् । त्वा । महिमा । सक्षत् । अवसे । महे । मित्रं । न । अवसे । ओजिष्ठ । त्रातः । अवितरिति । रथं । कं ।
चित् । अमर्त्य । अन्यं । अस्मत् । रिरिषेः । कं । चित् । अद्रिऽवः । रिरिक्षंतं । चित् । अद्रिऽवः । पाहि । नः ।
इंद्र । सुऽस्तुत । स्त्रिः । अवऽयाता । सदं । इत् । दुःऽमतीनां । देवः । सन् । दुःऽमतीनां । हंता । पापस्य । रक्षसः ॥ ११
ध

© Dharmartha Trust J&K. Digitized by eGangotri

त्राता। विप्रस्य। माऽवतः। अधा। हि। त्वा। जनिता। जीजनत्। वसोइति। रक्षःऽहनं। त्वा। जीजनत्।
वसोइति॥ १७॥ आ। इंद्र। याहि। उप। नः। पराऽवतः। न। अयं। अछ। विदथानिऽइव। सत्ऽपतिः।
अस्तं। राजाऽइव। सत्ऽपतिः। हवामहे। त्वा। वयं। प्रयस्वंतः। सुते। सचा। पुत्रासः। न। पितरं। वा
जऽसातये। मंहिष्ठं। वाजऽसातये। पिब। सोमं। इंद्र। सुवानं। अद्रिऽभिः। कोशेन। सिक्तं। अवतं।
न। वंसगः। ततृषाणः। न। वंसगः। मदाय। हर्यताय। ते। तुविःऽतमाय। धायसे। आ। त्वा। यच्छंतु
हरितः। न। सूर्यं। अहा। विश्वाऽइव। सूर्यं। अविंदत्। दिवः। निऽहितं। गुहा। निऽधिं। वेः। न। गर्भं।
परिऽवीतं। अश्मनि। अनंते। अंतः। अश्मनि। व्रजं। वज्री। गवांऽइव। सिसासन्। अंगिरःऽतमः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ छि॰
१२ अप। अवृणोत्। इषः। इंद्रः। परिऽवृताः। द्वारः। इषः। परिऽवृताः। ददृहाणः। वज्रं। इंद्रः। गभस्त्योः। क्षद्मऽइव। तिग्मं। असनाय। सं। श्यत्। अहिऽहत्याय। सं। श्यत्। संऽविव्यानः। ओजसा। शवःऽभिः। इंद्र। मज्मना। तष्टाऽइव। वृक्षं। वनिनः। नि। वृश्चसि। परश्वाऽइव। नि। वृश्चसि। त्वं। वृथा। नद्यः। इंद्र। सर्त्तवे। अच्छ। समुद्रं। असृजः। रथानऽइव। वाजऽयतः। रथानऽइव। इतः। ऊतीः। अयुंजत। समानं। अर्थं। अक्षितं। धेनूःऽइव। मनवे। विश्वऽदोहसः। जनाय। विश्वऽदोहसः॥१८॥ इमां। ते। वाचं। वसुऽयंतः। आयवः। रथं। न। धीरः। सुऽअपाः। अतक्षिषुः। सुम्नाय। त्वां। अतक्षिषुः। शुंभंतः। जेन्यं। यथा। वाजेषु। विप्र। वाजिनं। अत्यंऽइव। शवसे। सातये। धना। विश्वा। धनानि। सातये। मि १२

© Dharmartha Trust J&K. Digitized by eGangotri

नव।पुरः।नवतिं।इंद्र।पूरवे।दिवःऽदासाय।महि।दाशुषे।नृतो इति।वज्रेण।दाशुषे।नृतो इति।अति
थिऽग्वाय।शंबरं।गिरेः।उग्रः।अव।अभरत्।महः।धनानि।दयमानः।ओजसा।विश्वा।धनानि।
ओजसा।इंद्रः।सुमतः।सुऽयजमानं।आर्यं।प्र।आवत्।विश्वेषु।शतऽऊतिः।आजिषु।स्वःऽमीळ्हेषु।आ
जिषु।मनवे।शासत्।अव्रतान्।त्वचं।कृष्णां।अरंधयत्।धक्षन्।न।विश्वं।ततृषाणं।ओषति।नि।अर्श
सानं।ओषति।सूरः।चक्रं।प्र।वृहत्।जातः।ओजसा।प्रऽपित्वे।वाचं।अरुणः।मुषायति।ईशानः।आ
मुषायति।उशना।यत्।पराऽवतः।अजगन्।ऊतये।कवे।सुम्नानि।विश्वा।मनुषाऽइव।तुर्वणिः।अहा
विश्वाऽइव।तुर्वणिः।सः।नः।नव्येभिः।वृषऽकर्मन्।उक्थैः।पुरां।दर्तरिदर्त्तः।पायुऽभिः।पाहि।शग्मैः।दि

ति

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰ वःऽदास्वेभिः। इंद्र। स्तवानः। वरूधीथाः। अहोभिःऽइव। द्यौः॥१॥ इंद्राय। हि। द्यौः। असुरः। अनम्नत। इंद्रा
१३ याम मही। पृथिवी। वरीमऽभिः। द्युम्नऽसाता। वरीमऽभिः। इंद्रं। विश्वे। सऽजोषसः। देवासः। दधिरे। पुरः।
इंद्राय। विश्वा। सवनानि। मानुषा। रातानि। संतु। मानुषा। विश्वेषु। हि। त्वा। सवनेषु। तुंजते। समानं।
एकं। वृषऽमन्यवः। पृथक्। स्वरिति स्वः। सनिष्यवः। पृथक्। तं। त्वा। नावं। न। पर्षणिं। शूषस्य। धुरि।
13
धीमहि। इंद्रं। न। यज्ञैः। चितयंतः। आयवः। स्तोमेभिः। इंद्रं। आयवः। वि। त्वा। ततस्रे। मिथुनाः। अवस्य
वः। व्रजस्य। साता। गव्यस्य। निःऽसृजः। सक्षंतः। इंद्र। निःऽसृजः। यत्। गव्यंता। द्वा। जना। स्वः। यंता।
संऽऊहसि। आविः। करिक्रत्। वृषणं। सचाऽभुवं। वज्रं। इंद्र। सचाऽभुवं। विदुः। ते। अस्य। वीर्यस्य। १३

© Dharmartha Trust J&K. Digitized by eGangotri

पूर्वः।पुरः।यत्।इंद्र।शारदीः।अवऽआतिरः।ससहानः।अवःआतिरः।शासः।नो।इंद्र।मर्त्यं।अयज्युं।
शवसः।पते।महीं।अमुष्णाः।पृथिवीं।इमाः।अपः।मंदसानः।इमाः।अपः।आत।इत्रा।ते।अस्या।वीर्यं
स्या।चर्किरन्।मदेषु।रथन्।उशिजः।यत्।आविथ।सखिऽयतः।यत्।आविथ।चकृथ।कारं।एभ्यः
तं ।पृतनासु।प्रऽवंतवे।ते।अंन्यां।ऽअन्यां।नद्यं।सनिष्णत।श्रवस्यंतः।सनिष्णत।युजोइतिं।नः।अस्याः
।उषसः।सुषपते।हि।अर्कस्य।बोधि।हविषः।हवीमऽभिः।स्वःऽसाता।हवीमऽभिः।यत्।इंद्र।हंतवे।
मृधः।वृषा।वज्रिन्।चिकेतसि।आ।मे।अस्य।वेधसः।नवीयसः।मन्म।श्रुधि।नवीयसः।त्वं।तं।
इंद्र।वरधानः।अस्मऽयुः।अमित्रऽयंतं।तुविऽजात।मर्त्यं।वज्रेण।शूर।मर्त्यं।जहि।यः।नः।अघऽय

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ नि । श्रणु । षा । सु । श्रवःऽतमः । रिष्टं । न । यामन् । अप । भूतु । दुःऽमतिः । विश्वा । अप । भूतु । दुःऽमतिः ॥ २ ॥ त्वे

३५ या । वयं । मघऽवन् । पूर्व्ये । धने । इंद्र । त्वाऽऊताः । ससवाम । पृतन्यतः । वनुयाम । वनुष्यतः । नेदिष्ठे । अस्मि

न् । अहनि । अधि । वोच । नु । सुन्वते । अस्मिन् । यज्ञे । वि । चयेम । भरे । कृतं । वाजऽयंतः । भरे । कृतं । स्वःऽजे

षे । भरे । आप्रस्य । वक्मनि । उषःऽबुधः । स्वस्मिन् । अंजसि । क्राणस्य । स्वस्मिन् । अंजसि । अहन् । इं

द्रः । यथा । विदे । शीर्ष्णःऽशीर्ष्णः । उपऽवाच्यः । अस्मऽत्रा । ते । सध्र्यक् । सं । तु । रा । नयः । भद्राः । भद्रस्य । रा

प्रयः । नयः । न । नु । अंगऽत्वःऽथा । ते । शुष्मकृतेन । यस्मिन् । यज्ञे । वारं । अकृण्वत । क्षयं । ऋतस्य । वाः । असि ।

क्षयं । वि । तनु । वोचेः । अध । द्विता । अंतरिति । पश्यंति । रश्मिऽभिः । सः । घ । विदे । अनु । इंद्रः । गोऽएषणः ॥ ३४

© Dharmartha Trust J&K. Digitized by eGangotri

वेधुस्तिरःऽभ्यः । गोःऽएषणः । नु । इत्था । ते । पूर्वऽथा । च । प्रऽवाच्यं । यत् । अंगिरःऽभ्यः । अवृणोः । अप । व्रजं । इंद्र ।
शिक्षन् । अप । व्रजं । आ । एभ्यः । समान्या । दिशा । अस्मभ्यं । जेषि । योत्सि । च । सुन्वत्ऽभ्यः । रंधय । कं ।
चित् । अव्रतं । हृणायंतं । चित् । अव्रतं । सं । यत् । जनान् । क्रतुऽभिः । शूरः । ईक्षयत् । धने । हिते । तरुषंत । श्र
वस्यवः । प्र । यक्षंत । श्रवस्यवः । तस्मै । आयुः । प्रजाऽवत् । इत् । बाधे । अर्चंति । ओजसा । इंद्रे । ओक्यं । दि
धिषंत । धीतयः । देवान् । अच्छ । न । धीतयः । युवं । तं । इंद्रापर्वता । पुरःऽयुधा । यः । नः । पृतन्यात् । अप । तंऽतं ।
इत् । हतं । दूरे । चत्ताय । छंत्सत् । गहनं । यत् । इनक्षत् । अस्माकं । शत्रून् । परि । शूर । विश्वतः । दर्मा । दर्षी
ष्ट । विश्वतः । २२ । उभे इति । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सं । महीः । अनिंद्राः । अभि
वज्रेण । तंऽतं । इत् । हतं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰दि॰ वृश्च्य। यत्र। हताः। अमित्राः। वैलऽस्थानं। परि। तृळ्हाः। अशेरन्। अभिऽवृश्च्य। चित्। अद्रिऽवः। शीर्षा। या

१५ तुऽमतीनां। छिंधि। वटूरिणा। पदा। महाऽवटूरिणा। पदा। अव। आसां। मघऽवन्। जहि। शर्धः। यातुऽमती

नां। वैलऽस्थानके। अर्मके। महाऽवैलस्थे। अर्मके। यासां। तिस्रः। पंचाशतः। अभिऽव्लंगैः। अपऽअवपः।

तत्। सु। ते। मनायति। तकत्। सु। ते। मनायति। पिशंगऽभृष्टिं। अंभृणं। पिशाचिं। इंद्र। सं। मृण। सर्वं। र

क्षः। नि। बर्हय। अवः। महः। इंद्र। ददृहि। श्रुधि। नः। शुशोच। हि। द्यौः। क्षाः। न। भीषा। अद्रिऽवः। घृणात्। न।

भीषा। अद्रिऽवः। शुष्मिन्ऽतमः। हि। शुष्मिऽभिः। वधैः। उग्रेभिः। ईयसे। अपुरुषऽघ्नः। अप्रतिऽइत। शूर।

सत्वऽभिः। त्रिऽसप्तैः। शूर। सत्वऽभिः। वनोति। हि। सुन्वन्। क्षयं। परीणसः। सुन्वानः। हि। स्म। यजति। १५

© Dharmartha Trust J&K. Digitized by eGangotri

देवानां। अव। द्विषः॥
अव। द्विषः। सुन्वानः। इत्। सिसासति। सहस्रा। वाजी। अवृतः। सुन्वानाय। इन्द्रः। ददाति। आऽभुवं। रयिं।
ददाति। आऽभुवं॥ २२॥ आ। त्वा। जुवः। ररहाणाः। अभि। प्रयः। वायो इति। वहंतु। इह। पूर्वऽपीतये। सोमस्य।
पूर्वऽपीतये। ऊर्ध्वा। ते। अनु। सूनृता। मनः। तिष्ठतु। जानती। नियुत्वता। रथेन। आ। याहि। दावने। वायो इ
ति। मखस्य। दावने। मंदंतु। त्वा। मंदिनः। वायो इति। इंदवः। अस्मत्। क्राणासः। सुऽकृताः। अभिऽद्यवः। गो
भिः। क्राणाः। अभिऽद्यवः। यत्। ह। क्राणाः। इरध्यै। दक्षं। सचंते। ऊतयः। सध्रीचीनाः। नियुतः। दावने। धि
व यः। उप। ब्रुवते। ईं। धियः। वायुः। युंक्ते। रोहिता। वायुः। अरुणा। वायुः। रथे। अजिरा। धुरि। वोळ्हवे। वहिष्ठा। धु
रि। वोळ्हवे। प्र। बोधय। पुरंऽधिं। जारः। आ। ससतींऽइव। प्र। चक्षय। रोदसी इति। वासय। उषसः। श्रवसे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ वासय। उषसः। तुभ्यं। उषसः। शुचयः। पराऽवति। भद्रा। वस्त्रा। तन्वते। दंऽसु। रश्मिषु। चित्रा। नव्येषु। र
१६ श्मिषु। तुभ्यं। धेनुः। सबःऽदुघा। विश्वा। वसूनि। दोहते। अजनयः। मरुतः। वक्षणाभ्यः। दिवः। आ। व
क्षणाभ्यः। तुभ्यं। शुक्रासः। शुचयः। तुरण्यवः। मदेषु। उग्राः। इषणंत। भुर्वणि। अपां। इषंत। भुर्वणि। त्वां
16 त्सारी। दसमानः। भगं। ईट्टे। तक्वऽवीये। त्वं। विश्वस्मात्। भुवनात्। पासि। धर्मणा। असुर्यात्। पा
सि। धर्मणा। त्वं। नः। वायो इति। एषां। अपूर्व्यः। सोमानां। प्रथमः। पीतिं। अर्हसि। सुतानां। पीतिं।
अर्हसि। उतो इति। विहुत्मतीनां। विशां। ववर्जुषीणां। विश्वाः। इत्। ते। धेनवः। दुह्रे। आऽशिरं। घृतं।
दुह्रे। आऽशिरं। रुक्मा। स्तीर्णं। बर्हिः। उप। नः। याहि। वीतये। सहस्रेण। निऽयुता। नियुत्वते। श १६

© Dharmartha Trust J&K. Digitized by eGangotri

तिनीभिः।नियुत्वते।तुभ्यं।हि।पूर्वऽपीतये।देवाः।देवाय।येमिरे।प्र।ते।सुतासः।मधुऽमंतः।अस्थिरन्।
मदाय।क्रत्वे।अस्थिरन्।तुभ्यं।अयं।सोमः।परिऽपूतः।अद्रिऽभिः।स्पार्हा।वसानः।परि।कोशं।अर्षति।
शुक्रा।वसानः।अर्षति।तव।अयं।भागः।आयुषु।सोमः।देवेषु।हूयते।वह।वायो इति।निऽयुतः।याहि।
अस्मऽयुः।जुषाणः।याहि।अस्मऽयुः।आ।नः।निऽयुत्ऽभिः।शतिनीभिः।अध्वरं।सहस्रिणीभिः।उप।
याहि।वीतये।वायो इति।हव्यानि।वीतये।०ऋत्वियः।सऽरश्मिः।सूर्ये।सचा।अध्वर्युऽभिः।भरमाणाः।
अयंसत।वायो इति।शुक्राः।अयंसत।आ।वां।रथः।नियुत्वान्।वक्षत्।अवसे।अभि।प्रयांसि।सुऽधि
तानि।वीतये।वायो इति।हव्यानि।वीतये।पिबतं।मध्वः।अंधसः।पूर्वऽपेयं।हि।वां।हितं।वायो इति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰दि॰ आ। चंद्रेण। राधसा। आ। गतं। इंद्रः। च। राधसा। आ। गतं। आ। वां। धियः। ववृत्युः। अध्वरान्। उप। इमं। इंदुं।
१७ मर्मृजंत। वाजिनं। आशुं। अत्यं। न। वाजिनं। तेषां। पिबतं। अस्मयू इत्यस्मऽयू। आ। नः। गंतं। इह। ऊत्या। इं
द्रवायू इति। सुतानां। अद्रिऽभिः। युवं। मदाय। वाजऽदा। युवं। रथा। इमे। वां। सोमाः। अप्ऽसु। आ। सुताः। इह
। अध्वर्युऽभिः। भरमाणाः। अयंसत। वायो इति। शुक्राः। अयंसत। एते। वां। अभि। असृक्षत। तिरः। पवि
त्रं। आशवः। युवाऽयवः। अति। रोमाणि। अव्यया। सोमासः। अति। अव्यया। अति। वायो इति। ससतः।
याहि। शश्वतः। यत्र। ग्रावा। वदति। तत्र। गच्छतं। गृहं। इंद्रः। च। गच्छतं। वि। सूनृता। ददृशे। रीयते। घृतं। आ।
पूर्णया। निऽयुता। याथः। अध्वरं। इंद्रः। च। याथः। अध्वरं। अत्र। अह। तत्। वहेथे इति। मध्वः। आऽहुतिं। यं। १७

© Dharmartha Trust J&K. Digitized by eGangotri

अश्वत्थां। इषऽइति इष्वं। ना। आ। यवः। अस्मै इति। नः। संतु। आ। यवः। साके। गावः। सुवने। पव्येन। यवः। नाना। वा
योः इति। उप। दस्यंति। धेनवः। न। अपऽदस्यंति। धेनवः। इमे। येते। सु। वायोः इति। बाहूऽ ओजसः। अंतः
नदी इति। ते। पवयंति। उक्षणः। महि। आ। धर्तः। उक्षणः। धन्वन्। चित्। ये। अनाशवः। जीराः। चित्। आगिर। त।
ऽओकसः। सूर्यस्यऽइव। रश्मयः। दुःऽनियंतवः। हस्तयोः। दुःऽनियंतवः॥ २५॥ प्र। सुऽज्येष्ठं। निःऽचिर
भ्यो। बृहत्। नमः। हव्यां। मतिं। भरत। मरुत्ऽभ्यः। स्वादिष्ठं। मरुत्ऽभ्यः। ना। सं। राजा। घृता। सुनी
इति घृतऽआसुनी। यज्ञे। यज्ञा। सुपा। स्तुता। अधा। एनोः। सुजं। न। कुलेः। चन। आ। धृषे। देवं। त्वं। नु। चि
त्। आ। धृषे। अदर्शि। गातुः। उरवे। वरीयसी। पंथाः। ऋतस्य। सं। अयंस्त। रश्मिऽभिः। चक्षुः। भग

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ स्य । रश्मिऽभिः । द्युक्षं । मित्रस्य । सदनं । अर्यम्णः । वरुणस्य । च । अथ । दधाते इति । बृहत् । उक्थ्यं । व

१८ यः । उपऽस्तुत्यं । बृहत् । वयः । ज्योतिष्मतीं । अदितिं । धारयत्ऽक्षितिं । स्वःऽवतीं । आ । सचेते इति । दिवेऽ

दिवे । जागृऽवांसा । दिवेऽदिवे । ज्योतिष्मत् । क्षत्रं । आशाते इति । आदित्या । दानुनः । पती इति । मित्रः । त

18 योः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः । अयं । मित्राय । वरुणाय । शंऽतमः । सोमः । भू

तु । अवऽपानेषु । आऽभगः । देवः । देवेषु । आऽभगः । तं । देवासः । जुषेरत । विश्वे । अद्य । सऽजोषसः । तथा

। राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे । यः । मित्राय । वरुणाय । अविधत् । जनः । अन

र्वाणं । तं । परि । पातः । अंहसः । दाश्वांसं । मर्तं । अंहसः । तं । अर्यमा । अभि । रक्षति । ऋजुऽयंतं । अनु । १८

© Dharmartha Trust J&K. Digitized by eGangotri

व्रतं।उक्थैः।यः।एनोः।परिऽभूषति।व्रतं।स्तोमैः।आऽभूषति।व्रतं।नमः।दिवे।बृहते।रोदसीभ्यां।मि
त्राय।वोचं।वरुणाय।मीळ्हुषे।सुऽमृळीकाय।मीळ्हुषे।इंद्रं।अग्निं।उप।स्तुहि।द्युक्षं।अर्यमणं।भ
गं।ज्योक्।जीवंतः।प्रऽजया।सचेमहि।सोमस्य।ऊती।सचेमहि।ऊती।देवानां।वयं।इंद्रऽवंतः।मंसी
महि।स्वऽयशसः।मरुत्ऽभिः।अग्निः।मित्रः।वरुणः।शर्म।यंसन्।तत्।अश्याम।मघऽवानः।व
यं।च॥२७।२।इतिद्वितीयाष्टकेप्रथमोध्यायः॥ ॥ॐ॥सुषुमतृचमतिशक्करं।प्रप्रवलुधंपोष्णं
मस्तुश्रोषकेकादशवैश्वदेवीमैत्रावरुण्याश्विन्यास्तिस्रैंद्याग्नेयीमारुत्यैंद्राग्नीबार्हस्पत्यावैश्वव्यं दे
स्यात्रिष्टुप्पंचमीबृहतीवैश्वदेवमेतद्देवमन्यासामपिसूक्तप्रयोगेवैश्वदेवत्वंसूक्तभेदप्रयोगेयल्लिं

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ गं सा । देवता विद्दिषदेस्य स्तोना ऽदीपेतमा औचथ्य आग्नेयं तु द्विस्त्रिष्टुबंनं तु त्रिष्टुब्दशमी वा बळिः स्थास

१९ मिध आघि यं आनुष्टुभ मं सैंद्री ग्रतनयसीम स्त्रा वाऽग्नेयं तु नत्रिष्टुबं नेमतिग्रस्य प्रजा गतं तं पृष्ठ तपं वा सा

19 त्रिष्टुप्त्रिमूर्धानं कुथाम थीन्महः सवेराजं पुरुत्तच मौल्विहिं मित्रं नव मे त्रावरुणं हिज्जा गतं मे न्याघा युरं

सत्तं यजामे हचतुष्कं विश्नोः षड्वै स्य वं हि प्रयो जागतं सैद्रश्चा घस्त्र यो भवपे वा बोधिषक्ता भि नं स्वं सैत्रि

ष्टुभौ ॥ हरिः ॐ ॥ सुसुम । आ । याते । अद्रिऽभिः । गोऽश्रीताः । मत्सराः । इमे । सोमासः । मत्सराः । इमे । आ ।

राजाना । दिविऽस्पृशा । अस्मऽत्रा । गंतं । उप । नः । इमे । वां । मित्रावरुणा । गोऽआशिरः । सोमाः । शुक्राः ।

गोऽआशिरः । इमे । आ । याते । इंद्रवः । सोमासः । दधिऽआशिरः । सुतासः । दधिऽआशिरः । उत । वां । उषसः । १९

© Dharmartha Trust J&K. Digitized by eGangotri

बुधि। साकं। सूर्यस्य। रश्मिऽभिः। सुतः। मित्राय। वरुणाय। पीतये। चारुः। ऋताय। पीतये। तां। वां। धे
नुं। न। वासरीं। अंशुं। दुहंति। अद्रिऽभिः। सोमं। दुहंति। अद्रिऽभिः। अस्मऽत्रा। गंतं। उप। नः। अर्वांचा।
सोमऽपीतये। अयं। वां। मित्रावरुणा। नृऽभिः। सुतः। सोमः। आ। पीतये। सुतः॥ ३॥ प्रऽप्र। पूष्णः। तुवि
ऽजातस्य। शस्यते। महिऽत्वं। अस्य। तवसः। न। तंदते। स्तोत्रं। अस्य। न। तंदते। अर्चामि। सुम्नऽयन्। अ
हं। अंतिऽऊतिं। मयःऽभुवं। विश्वस्य। यः। मनः। आऽयुयुवे। मखः। देवः। आऽयुयुवे। मखः। प्र। हि। त्वा
। पूषन्। अजिरं। न। यामनि। स्तोमेभिः। कृण्वे। ऋणवः। यथा। मृधः। उष्ट्रः। न। पीपरः। मृधः। हुवे।
यत्। त्वा। मयःऽभुवं। देवं। सख्याय। मर्त्यः। अस्माकं। आंगूषान्। द्युम्निनः। कृधि। वाजेषु। द्युम्निनः

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ सुधि।यस्या।नो।पूषन्।सख्ये।विपन्यवः।क्रत्वा।चित्।संतः।अवसा।बुभुज्रिरे।इति।क्रत्वा।बुभुज्रि

२० रे।तं।अनु।त्वा।नवीयसीं।निःऽयुतं।रायं।ईमहे।अहेळमानः।उरुऽशंस।सरी।भव।वाजेऽवाजे।सरी

।भव।अस्याः।ऊं इति।सु।नः।उप।सातये।भुवः।अहेळमानः।ररिऽवान्।अजऽअश्व।श्रवस्यतां।

20 अजऽअश्व।ओ इति।सु।त्वा।वर्तीमहि।स्तोमेभिः।दस्म।साधुऽभिः।नहि।त्वा।पूषन्।अतिऽमन्ये

।आघृणे।न।ते।सख्यं।अपऽह्नुवे।।२।।अस्तु।श्रौषट्।पुरः।अग्निं।धिया।दधे।आ।नु।तत्।शर्धः।

दिव्यं।वृणीमहे।इंद्रवायूइति।वृणीमहे।यत्।ह।क्राणा।विवस्वति।नाभा।संऽदायि।नव्यसी।अ

ध।प्र।सु।नः।उप।यंतु।धीतयः।देवान्।अछ।न।धीतयः।यत्।ह।त्यत्।मित्रावरुणा।ऋतात्।अधि। २०

© Dharmartha Trust J&K. Digitized by eGangotri

आ । दृदाथे इति । सा॒ऽदृदाथे । अनृतं । स्वेन । मन्युना । दक्षस्य । स्वेन । मन्युना । युवोः । इत्था । अधि । सद्मऽसु । अ
पश्याम । हिरण्ययं । धीभिः । चन । मनसा । स्वेभिः । अक्षऽभिः । सोमस्य । स्वेभिः । अक्षऽभिः । युवां । स्तोमे
भिः । देवऽयंतः । अश्विना । आ । श्रावयंतःऽइव । श्लोकं । आ । यवः । युवां । हव्या । अभि । आ । यवः । युवोः । विश्वाः
। अधि । श्रियः । पृक्षः । च । विश्वऽवेदसा । प्रुषायंते । वां । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये । अचे
ति । दस्रा । वि । ऊं इति । नाकं । ऋण्वथः । युंजते । वां । रथऽयुजः । दिविऽइष्टिषु । अध्वस्मानः । दिविऽइष्टिषु । अधि
। वां । स्थाम । वंधुरे । रथे । दस्रा । हिरण्यये । पथाःऽइव । यंतौ । अनुऽशासता । रजः । अंजसा । शासता । रजः
शचीभिः । नः । शचीवसू इति शचीऽवसू । दिवा । नक्तं । दशस्यतं । मा । वां । रातिः । उप । दसत् । कदा । चन ।

© Dharmartha Trust J&K. Digitized by eGangotri

प·द्वि: अस्मत्रा।रातिः।कदा।चन।उ॥ वृषन्।इंद्र।वृषऽपानासः।इंदवः।इमे।सुताः।अद्रिऽसुतासः।उत्ऽभिदः।तु
२१ भ्यं।सुतासः।उत्ऽभिदः।ते।त्वा।मंदंतु।दावने।महे।चित्राय।राधसे।गीःऽभिः।गिर्वाहः।स्तवमानः।आ।
गहि।सुऽमृळीकः।नः।आ।गहि।ओ इति।सु।नः।अग्ने।शृणुहि।त्वं।ईळितः।देवेभ्यः।ब्रवसि।यज्ञियेभ्यः।
21 राजऽभ्यः।यज्ञियेभ्यः।यत्।ह।त्यां।अंगिरःऽभ्यः।धेनुं।देवाः।अदत्तन।वि।तां।दुह्रे।अर्यमा।कर्तरि।स
चा।एषः।तां।वेद।मे।सचा।मो इति।सु।वः।अस्मत्।अभि।तानि।पौंस्या।सना।भूवन्।द्युम्नानि।मा।
उत।जारिषुः।अस्मत्।पुरा।उत।जारिषुः।यत्।वः।चित्रं।युगेऽयुगे।नव्यं।घोषात्।अमर्त्यं।अस्मा
सु।तत्।मरुतः।यत्।च।दुस्तरं।दिधृत।यत्।च।दुस्तरं।दध्यङ्।ह।मे।जनुषं।पूर्वः।अंगिराः।प्रियऽमे २१

© Dharmartha Trust J&K. Digitized by eGangotri

धः। कण्वः। अत्रिः। मनुः। विदुः। ते। मे। पूर्वे। मनुः। विदुः। तेषां। देवेषु। आऽयतिः। अस्माकं। तेषु। नाभयः।
तेषां। पदेन। महि। आ। नमे। गिरा। इंद्राग्नी इति। आ। नमे। गिरा। होता। यक्षत्। वनिनः। वंत। वार्यं।
बृहस्पतिः। वेनैः। यजति। उक्षऽभिः। पुरुऽवारेभिः। उक्षऽभिः। जगृभ्म। दूरेऽआदिशं। श्लोकं। अद्रेः।
अध। त्मना। अधारयत्। अररिंदानि। सुऽक्रतुः। पुरु। सद्मानि। सुऽक्रतुः। ये। देवासः। दिवि। एका
दश। स्थ। पृथिव्यां। अधि। एकादश। स्थ। अप्सुऽक्षितः। महिना। एकादश। स्थ। ते। देवासः। यज्ञं। इमं।
जुषध्वं॥ ५॥ वेदिऽसदे। प्रियऽधामाय। सुऽद्युते। धासिंऽइव। प्र। भर। योनिं। अग्नये। वस्त्रेणऽइव। वा
सय। मन्मना। शुचिं। ज्योतिःऽरथं। शुक्रऽवर्णं। तमःऽहनं। अभि। द्विऽजन्मा। त्रिऽवृत्। अन्नं। ऋज्यते।

© Dharmartha Trust J&K: Digitized by eGangotri

प॰द्वि॰ संवत्सरे। ववृधे। जग्धं। ईमिति। पुनरिति। अन्यस्य। आसा। जिह्वया। जेन्यः। वृषा। नि। अन्येन। वनि

२२ नः। मृष्ट। वारणः। कृष्णऽप्रुतौ। वेविजे इति। अस्य। सऽक्षितौ। उभा। तरेते इति। अभि। मातरा। शिशुं। प्रा

चाऽजिह्वं। ध्वसयंतं। तृषुऽच्युतं। आ। साच्यं। कुपयं। वर्धनं। पितुः। मुमुक्ष्वः। मनवे। मानवस्यते। रघु

ऽद्रुवः। कृष्णऽसीतासः। ऊं इति। जुवः। असमनाः। अजिरासः। रघुऽस्यदः। वातऽजूताः। उप। युज्यंते। आ

शवः। आत्। अस्य। ते। ध्वसयंतः। वृथा। ईरते। कृष्णं। अभ्वं। महि। वर्पः। करिक्रतः। यत्। सीं। महीं। अ

वनिं। प्र। अभि। मर्मृशत्। अभिऽश्वसन्। स्तनयन्। एति। नानदत्। भूषन्। न। यः। अधि। बभ्रू

षु। नम्नते। वृषाऽइव। पत्नीः। अभि। एति। रोरुवत्। ओजायमानः। तन्वः। च। शुंभते। भीमः। न। शृङ्गं २२

© Dharmartha Trust J&K. Digitized by eGangotri

गा। द्विऽधा। बाहुः। गऽभिः। सः। संऽस्तिरः। विऽस्तिरः। सं। गृभायति। जानन्। एव। जानतीः। नित्यः। आ।

शये। पुनः। वर्धते। अपि। यंति। देव्यं। अन्यत्। वर्पः। पित्रोः। कृण्वते। सचा। तं। अग्रुवः। केशिनीः। सं।

मम्रुषीः। हि। रेभिरे। ऊर्ध्वाः। तस्थुः। प्र। आयवे। पुनरिति। तासां। जरां। प्रऽमुंचन्। एति। नानदत्। असुं। परं।

जनयन्। जीवं। अस्तृतं। अधीवासं। परि। मातुः। रिहन्। अह। तुविऽग्रेभिः। सत्वऽभिः। याति। विऽज्र

यः। वयः। दधत्। पत्ऽवते। रेरिहत्। सदा। अनु। श्येनी। सचते। वर्तनिः। अह। अस्माकं। अग्ने। म

घवत्ऽसु। दीदिहि। अध। श्वसीवान्। वृषभः। दमूनाः। अवऽअस्य। शिश्वः। मतीः। अदीदेः। वर्मऽ

इव। युत्ऽसु। परिऽजर्भुराणः। १०। इदं। अग्ने। सुऽधितं। दुःऽधितात्। अधि। प्रियात्। ऊं इति। चि

© Dharmartha Trust J&K. Digitized by eGangotri

१ऽहि त्। मन्म। नः। प्रेयः। अस्तु। ते। यत्। ते। शुक्रं। तन्वः। रोचते। शुचि। तेन। अस्मभ्यं। वनसे। रत्नं। आ। त्वं। रथा

२३ यानां। वै। उत। नः। गृहाय। नित्यऽअरित्रां। पत्ऽवतीः। रासि। अग्ने। अस्माकं। वीरान्। उत। नः। मघोनः।

जनान्। च। या। पारयात्। शर्म। या। च। अभि। नः। अग्ने। उक्थं। इत्। जुजुर्याः। द्यावा। क्षामा। सिंधवः। च।

23 स्वऽगूर्ताः। गव्यं। यव्यं। यंतः। दीर्घा। अहा। इषं। अरुण्यः। वरंत। ७। बट्। इत्था। तत्। वपुषे। धायि। दर्श नरं।

तं। देवस्य। भर्गः। सहसः। यतः। जनि। यत्। ईं। उप। ह्वरते। साधते। मतिः। ऋतस्य। धेनाः। अनयंत। स

स्रुतः। पृक्षः। वपुः। पितुऽमान्। नित्यः। आ। शये। द्वितीयं। आ। सप्तऽशिवासु। मातृषु। तृतीयं। अस्य

। वृषभस्य। दोहसे। दशऽप्रमतिं। जनयंत। योषणः। निः। यत्। ईं। बुध्नात्। महिषस्य। वर्पसः। ईशाना २३

© Dharmartha Trust J&K. Digitized by eGangotri

सः।शवसा।क्रंता।सूरयः।यत्।ईं।अनु।प्रऽदिवः।मध्वः।आऽधवे।गुहा।सन्तं।मातरिश्वा।मथायति।

प्र।यत्।पितुः।परमात्।नीयते।परि।आ।पृक्षुधः।वीरुधः।दंऽसु।रोहति।उभा।यत्।अस्य।जनुषं।

यत्।इन्वतः।आत्।इत्।यविष्ठः।अभवत्।घृणा।शुचिः।आत्।इत्।मातॄः।आ।अविशत्।यासु।आ

।शुचिः।अहिंस्यमानः।उर्विया।वि।ववृधे।अनु।यत्।पूर्वाः।अरुहत्।सनाऽजुवः।नि।नव्यसीषु।

अवरासु।धावते॥५॥आत्।इत्।होतारं।वृणते।दिविष्टिषु।भगंऽइव।पपृचानासः।ऋञ्जते।देवान्।

यत्।क्रत्वा।मज्मना।पुरुः।स्तुतः।मर्त्तं।शंसं।विश्वधा।वेति।धायसे।वि।यत्।अस्थात्।यजतः।

वातऽचोदितः।ह्वारः।न।वक्वा।जरणाः।अनाऽकृतः।तस्य।पत्मन्।धक्षुषः।कृष्णऽजंहसः।शुचिऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰
२५

जन्मनः। रजः। आ। विः। अध्वनः। रथः। न। यातः। शिक्वऽभिः। कृतः। यां। अंगेभिः। अरुषेभिः। ईयते। ०रु
हमासः। धक्षि। सूरयः। शरस्यऽइव। त्वेषथात्। ईषते। वयः। त्वया। हि। अग्ने। वरुणः। धृतऽव्रतः। मित्रः।
शाशद्रे। अर्यमा। सुऽदानवः। यत्। सां। अनु। क्रतुना। विश्वथा। विऽभुः। परिऽभूः। अजायथाः। त्वं। अ
ग्ने। शशमानाय। सुन्वते। रत्नं। यविष्ठ। देवऽतातिं। इन्वसि। तं। त्वा। नु। नव्यं। सहसः। युवन्। वयं। भ
गं। न। कारे। महिऽरत्न। धीमहि। अस्मे इति। रयिं। न। सुऽअर्थं। दमूनसं। भगं। दक्षं। न। पपृचासि। ध
र्णसिं। रश्मीनऽइव। यः। यमति। जन्मनी इति। उभे इति। देवानां। शंसं। ऋते। आ। च। सुऽक्रतुः। उत। न
नः। सुऽद्योत्मा। जीरऽअश्वः। होता। मंद्रः। शृणवत्। चंद्रऽरथः। सः। नः। नेषत्। नेषऽतमैः। अमूरः। अग्निः। २५

© Dharmartha Trust J&K. Digitized by eGangotri

धामं। सुवितं। वस्यः। अच्छ। अस्तावि। अग्निः। शिमीवत्ऽभिः। अर्कैः। सांऽराज्याय। प्रऽतरं। दधानः। अमी
इति। च। ये। मघऽवानः। वयं। च। मिहं। न। सूरः। अति। निः। ततन्युः॥ १०॥ संऽइद्धः। अग्ने। आ। वह। देवान्।
अद्य। यतऽस्रुचे। तंतुं। तनुष्व। पूर्व्यं। सुतऽसोमाय। दाशुषे। घृतऽवंतं। उप। मासि। मधुऽमंतं। तनूऽन
पात्। यज्ञं। विप्रस्य। माऽवतः। शशमानस्य। दाशुषः। शुचिः। पावकः। अद्भुतः। मध्वा। यज्ञं। मिमि
क्षति। नराशंसः। त्रिः। आ। दिवः। देवः। देवेषु। यज्ञियः। ईळितः। अग्ने। आ। वह। इंद्रं। चित्रं। इह। प्रियं।
ईळे। हि। त्वा। मतिः। मम। अच्छ। सुऽजिह्वा। वच्यंते। स्तृणानासः। यतऽस्रुचः। बर्हिः। यज्ञे। सुऽअध्वरे।
वृंजे। देवव्यचःऽतमं। इंद्राय। शर्म। सऽप्रथः। ०प्रऽयै। देवेभ्यः। महीः। पावकासः। पुरुऽस्पृहः। द्वारः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.दि॰ देवीः। असश्चतः॥ १७॥ आ। मंद्रमाने इति। उपाके इति। नक्तोषसा। सुऽपेशसा। यह्वी इति। ऋतस्य। मात
२५ रा। सीदतां। बर्हिः। आ। सुम्नयता। मंद्रऽजिह्वा। जुगुर्वणी इति। ०। स्त्रिधं। अद्य। दिविऽस्पृशं। शुचिः। देवेषु। अ
र्पिता। होत्रा। मरुत्ऽसु। भारती। ०। बर्हिः। सीदंतु। यज्ञियाः। तत्। नः। तुरीपं। अद्भुतं। पुरु। वा। अरं। पुरु।
त्मना। त्वष्टा। पोषाय। वि। स्यतु। रायः। नाभा। नः। अस्मऽयुः। अवऽसृजन्। उप। त्मना। देवान्। वनस्प पक्षि।
ते। ०। पूषण्ऽवते। मरुत्वते। विश्वऽदेवाय। वायवे। स्वाहा। गायत्रऽवेपसे। हव्यं। इंद्राय। कर्तन। स्वाहा
ऽकृतानि। आ। गहि। उप। हव्यानि। वीतये। इंद्र। आ। गहि। श्रुधि। हवं। त्वां। हवंते। अध्वरे॥ २१॥ प्रातर्य
सीं। नव्यसीं। धीतिं। अग्नये। वाचः। मतिं। सहसः। सूनवे। भर। अपां। नपात्। यः। वसुऽभिः। सह। प्रि २५

© Dharmartha Trust J&K. Digitized by eGangotri

यः। होता। पृथिव्यां। नि। असीदत्। ऋत्वियः। सः। जायमानः। परमे। विऽओमनि। आविः। अग्निः। अभवत्।
मातरिश्वने। अस्य। क्रत्वा। संऽइधानस्य। मज्मना। प्र। द्यावा। शोचिः। पृथिवी इति। अरोचयत्। अस्य।
त्वेषाः। अजराः। अस्य। भानवः। सुऽसंदृशः। सुऽप्रतीकस्य। सुऽद्युतः। भाऽत्वक्षसः। अति। अक्तुः। न। सिं
धवः। अग्नेः। रेजंते। अससंतः। अजराः। यं। आऽईरिरे। भृगवः। विश्वऽवेदसं। नाभा। पृथिव्याः। भुवन
स्य। मज्मना। अग्निं। तं। गीःऽभिः। हिनुहि। स्वे। आ। दमे। यः। एकः। वस्वः। वरुणः। न। राजति। न। यः। व
राय। मरुतांऽइव। स्वनः। सेनाऽइव। सृष्टा। दिव्या। यथा। अशनिः। अग्निः। जंभैः। तिगितैः। अत्ति। भर्वति
। योधः। न। शत्रून्। सः। वना। नि। ऋंजते। कुवित्। नः। अग्निः। उचथस्य। वीः। असत्। वसुः। कुवित्।

© Dharmartha Trust J&K. Digitized by eGangotri

वसुऽभिः।कामं।आ।वरत्।चोदः।कुवित्।तुतुज्यात्।सातये।धियः।शुचिऽप्रतीकं।तं।अया।गृणे।धिया।
घृतऽप्रतीकं।वः।ऋतस्य।धूःऽसदं।अग्निं।मित्रं।न।संऽइधानः।ऋंजते।इंधानः।अक्रः।विदथेषु।दीद्यत्।
शुक्रऽवर्णां।उत्।ऊं इति।नः।यंसते।धियं।अप्रऽयुच्छन्।अप्रयुच्छत्ऽभिः।अग्ने।शिवेभिः।नः।पायुऽभिः।
पाहि।शग्मेभिः।अदब्धेभिः।अदृप्तेभिः।इष्टे।अनिमिषत्ऽभिः।परि।पाहि।नः।जाः॥१२॥ ७ति।प्र।होता।
व्रतं।अस्य।मायया।ऊर्ध्वां।दधानः।शुचिऽपेशसं।धियं।अभि।स्रुचः।क्रमते।दक्षिणाऽआवृतः।याः।अस्य।
धाम।प्रथमं।ह।निंसते।अभि।ईं।ऋतस्य।दोहनाः।अनूषत।योनौ।देवस्य।सदने।परिऽवृताः।अपां।उ
पऽस्थे।विऽभृतः।यत्।आ।अवसत्।अध।स्वधाः।अधयत्।याभिः।ईयते।सुवृषनः।सः।वयसा।नत्।इ २६

© Dharmartha Trust J&K. Digitized by eGangotri

त्।वपुः।समानं।अर्थं।विऽतरित्रता।मिथः।आ।त्वां।ईं।भगः।न।हव्यः।सं।अस्मत्रा।आ।वोऽकुः।न।रश्मीन्

सं।अयंस्त।सारथिः।यं।ईं।द्वा।सऽवयसा।सपर्यतः।समाने।योना।मिथुना।संऽओकसा।दिवा।न।न

क्तं।पलितः।युवा।अजनि।पुरु।चरन्।अजरः।मानुषा।युगा।तं।ईं।हिन्वंति।धीतयः।दश।व्रिशः।देवं।

मर्तासः।ऊतये।हवामहे।धनोः।अधि।प्रऽवतः।आ।सः।ऋण्वति।अभिव्रजत्ऽभिः।वयुना।नवा।अ

धित।त्वं।हि।अग्ने।दिव्यस्य।राजसि।त्वं।पार्थिवस्य।पशुपाःऽइव।त्मना।एनीइति।ते।एनेइति।बृहती

इति।अभिःश्रिया।हिरण्ययीइति।वक्वरीइति।बर्हिः।आशातेइति।अग्ने।जुषस्व।प्रति।हर्य।तत्।वचः।

।मंद्र।स्वधाऽवः।ऋतऽजात।सुक्रतोइति।सुऽक्रतो।यः।विश्वतः।प्रत्यङ्।असि।दर्शतः।रण्वः।संऽदृष्टौ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ २८ 27

पितुमान्ऽइव । क्षयः ॥ १३ ॥ तं । पृछत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते । त
स्मिन् । संति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः । तं । इत् । पृछंति । न ।
सिमः । वि । पृछति । स्वेनऽइव । धीरः । मनसा । यत् । अग्रभीत् । न । मृष्यते । प्रथमं । न । अपरं । वचः । अ
स्य । क्रत्वा । सचते । अप्रऽदृपितः । तं । इत् । गछंति । जुह्वः । तं । अर्वतीः । विश्वानि । एकः । शृणवत् । वचां
सि । मे । पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अछिद्रऽऊतिः । शिशुः । आ । अदत्त । सं । रभः । उपऽस्थायं ।
चरति । यत् । संऽआरत । सद्यः । जातः । तत्सार । युज्येभिः । अभि । श्वांतं । मृशते । नांद्ये । मुदे । यत् । ईं ।
गछंति । उशतीः । अपिऽस्थितं । सः । ईं । मृगः । अप्यः । वनऽर्गुः । उप । त्वचि । उपऽमस्यां । नि । धायि । वि । २८

© Dharmartha Trust J&K. Digitized by eGangotri

अब्रवीत्।वयुना।मर्त्येभ्यः।अग्निः।विद्वान्।ऋतऽचित्।हि।सत्यः॥३४॥त्रिऽमूर्धानं।सप्तऽरश्मिं।
गृणीषे।अनूनं।अग्निं।पित्रोः।उपऽस्थे।निऽसत्तं।अस्य।चरतः।ध्रुवस्य।विश्वा।दिवः।रोचना।
आपप्रिऽवांसं।उक्षा।महान्।अभि।ववक्षे।एने इति।अजरः।नस्थौ।इतःऽऊतिः।ऋष्वः।ऊर्व्योः।प
दः।नि।दधाति।सानौ।रिहंति।ऊधः।अरुषासः।अस्य।समाने।वत्सं।अभि।संचरंती इति संऽच
रंती।विष्वक्।धेनू इति।वि।चरतः।सुमेके इति सुऽमेके।अनपऽवृज्यान्।अध्वनः।मिमाने इति।
विश्वान्।केतान्।अधि।महः।दधाने इति।धीरासः।पदं।कवयः।नयंति।नाना।हृदा।रक्षमाणाः
।अजुर्यं।सिसासंतः।परि।अपश्यंत।सिंधुं।आविः।एभ्यः।अभवत्।सूर्यः।नॄन्।दिदृक्षेण्यः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.हि:
२८
28

परि। काष्ठा सु।जेन्यः। ईके।न्यः। मुहः। अर्भाय। जीवसे। पुरुऽत्रा। आयत्। अभवत्। सूः। अह। एभ्यः। गर्भे
भ्यः। मघऽवा। विश्वऽदर्शतः॥ ३८॥ कथा। ते। अग्ने। शुचयन्तः। आयोः। ददाशुः। वाजेभिः। आशुषाणाः
उभे इति। यत्। तोके इति। तनये। दधानाः। ऋतस्य। सामन्। रणयन्त। देवाः। बोधा। मे। अस्य। वचसः
। यविष्ठ। मंहिष्ठस्य। प्रऽभृतस्य। स्वधाऽवः। पीयति। त्वः। अनु। त्वः। गृणाति। वंदारुः। ते। तन्वं। वंदे।
अग्ने। ये। पायवः। मामतेयं। ते। अग्ने। पश्यन्तः। अंधं। दुःऽइतात्। अरक्षन्। ररक्ष। तान्। सुऽकृ
तः। विश्वऽवेदाः। दिप्सन्तः। इत्। रिपवः। न। अह। देभुः। यं। नः। अग्ने। अरिऽवान्। अघऽयुः। अरा
तिऽवा। मर्चयति। द्वयेन। मंत्रः। गुरुः। पुनः। अस्तु। सः। अस्मै। अनु। मृक्षीष्ट। तन्वं। दुःऽउक्तैः। उत। २८

© Dharmartha Trust J&K. Digitized by eGangotri

वा। यः। सहस्य। प्र। विद्वान्। मर्तः। मर्तं। मर्चयति। द्वयेन। अतः। पाहि। स्तवमान। स्तुवंतं। अग्ने। माकिः। नः।
दुःऽइताय। धायीः॥१३॥ मथीत्। यत्। ईं। विष्टः। मातरिश्वा। होतारं। विश्वऽअप्सुं। विश्वऽदेव्यं। नि। यं। दधुः। मनुष्यासु।
विक्षु। स्वः। न। चित्रं। वपुषाय। विभाऽवं। ददानं। इत्। न। ददभंत। मन्म। अग्निः। वरूथं। मम। तस्य। चाकन्।
जुषंत। विश्वानि। अस्य। कर्म। उपऽस्तुतिं। भरमाणस्य। कारोः॥ नित्ये। चित्। नु। यं। सदने। जगृभ्रे। प्र-
शस्तिऽभिः। दधिरे। यज्ञियासः। प्र। सु। नयंत। गृभयंतः। इष्टौ। अश्वासः। न। रथ्यः। ररहाणाः॥ पुरूणि।
दस्मः। नि। रिणाति। जंभैः। आत्। रोचते। वने। आ। विभाऽवा। आत्। अस्य। वातः। अनु। वाति। शोचिः।
अस्तुः। न। शर्यां। असनां। अनु। द्युन्। न। यं। रिपवः। न। रिषण्यवः। गर्भे। संतं। रेषणाः। रेषयंति। अं-

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰
२९
29

धाः।अपश्याः।न।दभन्।अभिख्या।नित्यासः।ईं।प्रेतारः।अरक्षन्॥१७॥महः।सः।रायः।आ।ईषते।
पतिः।दन्।इनः।इनस्य।वसुनः।पदे।आ।उप।ध्रजन्तं।अद्रयः।विधन्।इत्।सः।यः।वृषा।नरां।न।रोद
स्योः।श्रवःऽभिः।अस्ति।जीवपीतऽसर्गः।प्र।यः।सस्राणः।शिश्रीत।योनौ।आ।यः।पुरं।नार्मिणीं।अ
दीदेत्।अत्यः।कविः।नभन्यः।न।अर्वा।सूरः।न।रुरुक्वान्।शतऽआत्मा।अभि।द्विऽजन्मा।त्री।रोच
नानि।विश्वा।रजांसि।शुशुचानः।अस्थात्।होता।यजिष्ठः।अपां।सधऽस्थे।अयं।सः।होता।यः।द्वि
ऽजन्मा।विश्वा।दधे।वार्याणि।श्रवस्या।मर्तः।यः।अस्मै।सुऽतुकः।ददाश॥१८॥पुरु।त्वा।दाश्वान्।वो
चे।अरिः।अग्ने।तव।स्वित्।आ।तोदस्यऽइव।शरणे।आ।महस्य।वि।अनिनस्य।धनिनः।प्रऽहोषे। २९

© Dharmartha Trust J&K. Digitized by eGangotri

चित्। आ। ररुषः। कदा। चन। प्रऽजिगतः। अदेवऽयोः। सः। रेद्रुः। विप्रा। मर्त्यैः। मुहुः। ग्ना। धनऽनमः। दिवि। प्रऽस्र

इत्वाते। अग्ने। वनुषः। स्याम॥१३॥ मित्रं। न। यं। शिम्या। गोषु। गव्यवः। सुऽआध्यः। विदथे। अप्सु। जीज

नन्। अरेजेतां। रोदसी इति। पाजसा। गिरा। प्रति। प्रियं। यजतं। जनुषां। अवः। यत्। हा। सत्। वां। पुरुऽमी

ळ्हस्य। सोमिनः। प्र। मित्रासः। न। दधिरे। सुऽआभुवः। अध। क्रतुं। विदतं। गातुं। अर्चते। उत। श्रुतं। वृष

णा। पस्त्यऽवतः। आ। वां। भूषन्। क्षितयः। जन्म। रोदस्योः। प्र। वाच्यं। वृषणा। दक्षसे। महे। यत्। ईं। ऋता

यं। भरथः। यत्। अर्वते। प्र। होत्रया। शिम्या। वीथः। अध्वरं। प्र। सा। क्षितिः। असुरा। या। महि। प्रिया।

ऋतऽवाना। ऋतं। आ। घोषथः। बृहत्। युवं। दिवः। बृहतः। दक्षं। आऽभुवं। गां। न। धुरि। उप। युंजाथे इति।

© Dharmartha Trust J&K. Digitized by eGangotri

१।द्दि अपः। मही इति। अत्र। महिना। वारं। कृण्वथः। अरेणवः। तुजः। आ। सद्मन्। धेनवः। स्वरंति। ताः। उप

३० रऽतानि। सूर्यं। आ। निःऽम्रुचः। उषसः। तक्ववीःऽइव। रथं। आ। वां। ऋतऽया। केशिनीः। अनूषत। मित्र

। यत्र। वरुणा। गातुं। अर्चथः। अव। त्मना। सृजतं। पिन्वतं। धियः। युवं। विप्रस्य। मन्मनां। इरज्यथः। यः

30 वां। यज्ञैः। शशमानः। ह। दाशति। कविः। होता। यजति। मन्मऽसाधनः। उप। अह। तं। गच्छथः। वीथः।

अध्वरं। अच्छ। गिरः। सुऽमतिं। गंतं। अस्मयू इत्यस्मऽयू। युवां। यज्ञैः। प्रथमा। गोभिः। अंजते। ऋत

ना। वाना। मनसः। न। प्रऽयुक्तिषु। भरंति। वां। मन्मना। संऽयता। गिरः। अदृप्यता। मनसा। रेवत्। आ। शाथे

इति। रेवत्। वयः। दधाथे इति। रेवत्। आशाथे इति। नरा। मायाभिः। इतःऽऊति। माहिनं। न। वां। द्यावः। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

न । उत । सिंधवः ।

अहऽभिः । न । देवः । स्वां । पणयः । न । आ । नभ्रुः । मघं ॥ २३ ॥ युवं । वस्त्राणि । पीवसा । वसाथे इति । युवोः ।
अच्छिद्राः । मंतवः । ह । सर्गाः । अव । अतिरतं । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथे इति ।
एतत् । चन । त्वः । वि । चिकेतत् । एषां । सत्यः । मंत्रः । कविऽशस्तः । ऋघावान् । त्रिःऽअश्रिं । हंति । चतुःऽ
अश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् । अपात् । एति । प्रथमा । पत्ऽवतीनां । कः । तत् । वां । मित्रा
वरुणा । उरा । चिकेत । गर्भः । भारं । भरति । आ । चित् । अस्य । ऋतं । पिपर्ति । अनृतं । नि । तारीत् । प्रऽयंतं । इत्
। परि । जारं । कनीनां । पश्यामसि । न । उपऽनिपद्यमानं । अनवऽपृग्णा । विऽतता । वसानं । प्रियं । मि
त्रस्य । वरुणस्य । धाम । अनश्वः । जातः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्वऽसानुः । अचि

© Dharmartha Trust J&K. Digitized by eGangotri

प. द्वि तां।ब्रह्म।जुजुषुः।युवां।नः।प्र।मित्रे।धाम।वरुणे।गृणंतः।आ।धेनवः।मामतेयं।अवंतीः।ब्रह्मऽप्रियं।पीप
३१ यन्।सस्मिन्।ऊधन्।पिप्वः।मित्रेन।वसुनानि।विद्वान्।आसा।आऽविवासन्।अदितिं।उरुष्येत्।आ
।वां।मित्रावरुणा।हव्यऽजुष्टिं।नमसा।देवौ।अवसा।ववृत्यां।अस्माकं।[illegible] ब्रह्म।पृतनासु।सह्याः।अ
31 स्माकं।वृष्टिः।दिव्या।सुऽपारा।ररा।यजामहे।वां।महः।सऽजोषाः।हव्येभिः।मित्रावरुणा।नमःऽभिः।
घृतैः।घृतस्नू इति घृतऽस्नू।अध।यत्।वां।अस्मे इति।अध्वर्यवः।न।धीतिऽभिः।भरंति।प्र।स्तुतिऽभिः।वां।
धाम।न।प्रऽयुक्तिः।अयामि।मित्रावरुणा।सुऽवृक्तिः।अनक्ति।यत्।वां।विदथेषु।होता।सुम्नं।वां।सूरिः त्रिवृ०
।वृषणौ।इयक्षन्।पीपाय।धेनुः।अदितिः।ऋताय।जनाय।मित्रावरुणा।हविःऽदा।हिनोति।यत्।वां। ३१

© Dharmartha Trust J&K. Digitized by eGangotri

विदथे। सपर्यन्। सः। रातऽहव्यः। मानुषः। न। होता। उत। वां। विक्षु। मद्यासु। अंधः। गावः। आपः। च। पी
पयंत। देवीः। उतो इति। नः। अस्य। पूर्व्यः। पतिः। दन्। वीतं। पातं। पयसः। उस्रियायाः॥ २३॥ विष्णोः। नु। कं।
वीर्याणि। प्र। वोचं। यः। पार्थिवानि। विऽममे। रजांसि। यः। अस्कभायत्। उत्ऽतरं। सधऽस्थं। विऽचक्र
माणः। त्रेधा। उरुऽगायः। प्र। तत्। विष्णुः। स्तवते। वीर्येण। मृगः। न। भीमः। कुचरः। गिरिऽस्थाः। यस्य। उ
रुषु। त्रिषु। विऽक्रमणेषु। अधिऽक्षियंति। भुवनानि। विश्वा। प्र। विष्णवे। शूषं। एतु। मन्म। गिरिऽक्षिते।
उरुऽगायाय। वृष्णे। यः। इदं। दीर्घं। प्रऽयतं। सधऽस्थं। एकः। विऽममे। त्रिऽभिः। इत्। पदेभिः। यस्य। त्री। पू
र्णा। मधुना। पदानि। अक्षीयमाणा। स्वधया। मदंति। यः। ऊं इति। त्रिऽधातु। पृथिवीं। उत। द्यां। एकः। दा

© Dharmartha Trust J&K. Digitized by eGangotri

प.दि धार। भुवनानि। विश्वा। तत्। अस्य। प्रियं। अभि। पाथः। अश्यां। नरः। यत्र। देवऽयवः। मदंति। उरुऽक्रम
३२ स्य। सः। हि। बंधुः। इत्था। विष्णोः। पदे। परमे। मध्वः। उत्सः। ता। वां। वास्तूनि। उश्मसि। गमध्यै। यत्र। गावः।
भूरिऽशृंगाः। अयासः। अत्र। अह। तत्। उरुऽगायस्य। वृष्णः। परमं। पदं। अव। भाति। भूरि॥ २१॥ ०॥ अं
धसः। धियाऽयते। महे। शूराय। विष्णवे। च। अर्चत। या। सानुनि। पर्वतानां। अदाभ्या। महः। तस्थतुः।
अर्वताऽइव। साधुना। त्वेषं। इत्था। संऽअरणं। शिमीऽवतोः। इंद्राविष्णू इति। सुतऽपाः। वां। उरुष्यति।
या। मर्त्याय। प्रतिऽधीयमानं। इत्। कृशानोः। अस्तुः। असनां। उरुष्यथः। ताः। ईं। वर्धंति। महि। अस्य।
पौंस्यं। नि। मातरा। नयति। रेतसे। भुजे। दधाति। पुत्रः। अवरं। परं। पितुः। नाम। तृतीयं। अधि। रोच ३२

© Dharmartha Trust J&K. Digitized by eGangotri

ने॥ द्विवः॥ न तत्ऽतत्। इत्। अस्य। पौंस्यं। गृणीमसि। इनस्य। त्रातुः। अवृकस्य। मीळ्हुषः। यः। पार्थिवानि।

त्रिऽभिः। इत्। विगामऽभिः। उरु। क्रमिष्ट। उरुऽगायाय। जीवसे॥ द्वे इति। इत्। अस्य। क्रमणे इति। स्वःऽदृशः

। अभिऽख्याय। मर्त्यः। भुरण्यति। तृतीयं। अस्य। नकिः। आ। दधर्षति। वयः। चन। पतयन्तः। पतत्रिणः॥

चतुःऽभिः। साकं। नवतिं। च। नामऽभिः। चक्रं। न। वृत्तं। व्यतीन्। अवीविपत्। बृहत्ऽशरीरः। विऽमिमानः

। ऋक्ऽभिः। युवा। अकुमारः। प्रति। एति। आऽहवं॥ २५॥ भव। मित्रः। न। शेव्यः। घृतऽआसुतिः। विभूत्

तऽद्युम्नः। एवऽयाः। ऊं इति। सऽप्रथाः। अध। ते। विष्णो इति। विदुषा। चित्। अर्ध्यः। स्तोमः। यज्ञः। च। राध्यः

। हविष्मता। यः। पूर्व्याय। वेधसे। नवीयसे। सुमत्ऽजानये। विष्णवे। ददाशति। यः। जातं। अस्य। महतः।

© Dharmartha Trust J&K. Digitized by eGangotri

महि। प्रवन्ता। सः। इन्द्र। ऊं इति। अर्वत्ऽभिः। युज्यं। चित्। अभि। असत्। तं। ऊं इति। स्तोतारः। पूर्व्यं। यथा। विद
ऽऋतस्य। गर्भं। जनुषा। विपर्त्तन। आ। अस्य। जानंतः। नाम। चित्। विवक्तन। महः। ते। विष्णो इति। सुऽ
मतिं। भजामहे। तं। अस्य। राजा। वरुणः। तं। अश्विना। क्रतुं। सचंत। मारुतस्य। वेधसः। दाधार। दक्षं। उत्
ऽतमं। अहः। विदं। व्रजं। च। विष्णुः। सखिऽवान्। अप। ऊर्णुते। आ। यः। विवाय। सचथाय। दैव्यः। इंद्राय।
विष्णुः। सुऽकृते। सुकृत्ऽतरः। वेधाः। अजिन्वत्। त्रिऽसधस्थः। आर्यं। ऋतस्य। भागे। यजमानं। आ। अ
भजत्॥ २१॥ अबोधि। अग्निः। ज्मः। उत्। एति। सूर्यः। वि। उषाः। चंद्रा। मही। आवः। अर्चिषा। अयुक्षा
तां। अश्विना। यातवे। रथं। प्र। असावीत्। देवः। सविता। जगत्। पृथक्। यत्। युंजाथे इति। वृषणा। ३३

© Dharmartha Trust J&K. Digitized by eGangotri

अश्विना। रथं। घृतेन। नः। मधुना। क्षत्रं। उक्षतं। अस्माकं। ब्रह्म। पृतनासु। जिन्वतं। वयं। धना। शूरऽसा
ता। भजेमहि। अर्वाङ्। त्रिऽचक्रः। मधुऽवाहनः। रथः। जीरऽअश्वः। अश्विनोः। यातु। सुऽस्तुतः। त्रिऽवंधु
रः। मघऽवा। विश्वऽसौभगः। शं। नः। आ। वक्षत्। द्विऽपदे। चतुःऽपदे।० मधुऽमत्या। नः। कशया। मिमि
क्षतं।० युवं। ह। गर्भं। जगतीषु। धत्थः। युवं। विश्वेषु। भुवनेषु। अंतरिति। युवं। अग्निं। च। वृषणौ। अपः।
च। वनस्पतीन्। अश्विनौ। ऐरयेथां। युवं। ह। स्थः। भिषजा। भेषजेभिः। अथो इति। ह। स्थः। रथ्या। रथ्ये
भिरिति रथ्येभिः। अथो इति। ह। क्षत्रं। अधि। धत्थः। उग्रा। यः। वां। हविष्मान्। मनसा। ददाश॥ २७॥
इति द्वितीयाष्टके द्वितीयोध्यायः॥ ॥ ॐ॥ वसू अंत्यानुष्टुप् पंचम्यावापंचपानापृथिवीयंतुजागतं

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ तुतेहि किमुश्रेष्ठः पङ्क्तनार्भवं त्रिरुवंतं मानो अधिकां भ्यस्तुलिस्तुत नीयापघ्नौजगत्सौयद्कं दः सभो
३५ नोस्यद्विपं वाशदल्पस्तवं लेतस्संशायोस्थापनघ्नभ्नघ्नालिवाक्यान्यत्रघ्नायेणज्ञानमोक्षाक्षरघ्नशंसा
चपंचपादं स्ताकें आनौंयक्रायत्रेयंसशिंके सनाधर्मभंगौरीरलिजगत्यंएलदंतंतुवेभ्वदेवंलस्याः
34 समुद्राइलिवाचः समुद्रा आपोक्षरं सावस्तारपंक्तिः शकमयमलि शकधूमं उक्षाणं पृश्निमिति सोम
स्यच्यः केशिनइत्यग्निः सूर्यो वायुश्चकेशिनश्चत्वारियाग्वाचं इन्द्रं मित्रं सौर्यो द्वादशेति संवत्सरसंस्थ
कालचक्रवर्णनं यस्तेसरस्वत्यै यज्ञेन साध्येभ्यः परानुष्टुप् सोरीपर्जन्याग्निदेवनावोत्यासरस्वते
सूर्यायवाकपापंचोनासंवादस्तनीयाघमुनोमरुतांवास्यमंसस्त योगरत्यस्यवाशिष्टाइंद्रस्यैकाद ३५

© Dharmartha Trust J&K. Digitized by eGangotri

श्रीवमरत्वां स्त्विंद्रो देवता। हरिः ऽऊं मावस्रू इति। रुद्रा। पुरुमंत्रू इति पुरुऽमंत्रो। रधंतो। दशस्यतं। नः। वृ
षणौ। अभिष्टौ। दस्रा। हा। यन्तो। रक्षणः। औचथ्यः। वां। प्राय्यतां। सस्नाथे इति। अर्कवाभिः। ऊती। कः। वां। दाश
त्। सुऽमनये। चित्। अस्यै। वस्रू इति। यता। धेथे इति। नमसा। पदा। गोः। जिगतं। अस्मे इति। रेवतीः। पुरुऽधीः
। कामप्रेण ऽइव। मनसा। चरन्ता। युक्तः। हा। यत्। वां। सौग्या। यां। पेरुः। विमध्यो। अर्णसः। धायि। पुज्रः। उपा
वां। अवः। शरणं। गमेयं। श्रूरः। न। अज्मा। पतयत्ऽभिः। अं। यैः। उपऽस्तुतिः। औचथ्यं। उरुष्येतां। मा। मां।
इमे इति। पतत्रिणी इति। वि। दुग्धां। मा। मां। एधः। दशऽतयः। चितः। धाक्। प्र। यत्। वां। बद्धः। त्मनि। खा
दति। क्षां। न। मा। गरन्। नद्यः। मातृऽतमाः। दासाः। यत्। ईं। सुऽसमुब्धं। अवः। अधुः। शिरः। यत्। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ स्य । त्रैतनः । विऽतक्षत् । स्वयं । दासः । उरः । अंसौ । अपि । ग्धेति ग्ध । दीर्घऽतमाः । मामतेयः । जुजुर्वान् । दशमे ।
३५ युगे । ... अपां । अर्थं । यतीनां । ब्रह्मा । भवति । सारथिः ॥ १ ॥ प्र । द्यावा । यज्ञैः । पृथिवी इति । ऋतऽवृधा । मही
35 इति । स्तुषे । विदथेषु । प्रऽचेतसा । देवेभिः । ये इति । देवपुत्रे इति देवऽपुत्रे । सुऽदंससा । इत्था । धिया । वार्याणि ।
प्रऽभूषतः । उत । मन्ये । पितुः । अद्रुहः । मनः । मातुः । महि । स्वऽतवः । तत् । हवीमऽभिः । सुऽरेतसा । पितरा । भूम ।
चक्रतुः । उरु । प्रऽजायाः । अमृतं । वरीमऽभिः । ते । सूनवः । सुऽअपसः । सुऽदंससः । मही इति । जज्ञुः । मातरा । पूर्व-
ऽचित्तये । स्थातुः । च । सत्यं । जगतः । च । धर्मणि । पुत्रस्य । पाथः । पदं । अद्वयाविनः । ते । मायिनः । ममिरे । सुऽ एम
प्रऽचेतसः । जामी इति । सयोनी इति सऽयोनी । मिथुना । सं । ओकसा । नव्यंऽनव्यं । तन्तुं । आ । तन्वते । दि ३५

© Dharmartha Trust J&K. Digitized by eGangotri

वि। समुद्रे। अंतरिति। कवयः। सुऽदीतयः। नत्। राधः। अपाः। सवितुः। वरेण्यं। वयं। देवस्य। प्रऽसवे। मनामहे।
अस्मभ्यं। द्यावापृथिवी इति। सुऽचेतुना। रयिं। धत्तं। वसुऽमंतं। शतऽग्विनं॥ २॥ ते इति। हि। द्यावापृथि
वी इति। विश्वऽशंभुवा। ऋतवरी इत्यृतऽवरी। रजसः। धारयत्कवी इति धारयत्ऽकवी। सुजन्मनी इति
सुऽजन्मनी। धिषणे इति। अंतः। ईयते। देवः। देवी इति। धर्मणा। सूर्यः। शुचिः॥ ३॥ उरुऽव्यचसा। महिनी इति। अ च
सश्चता। पिता। माता। च। भुवनानि। रक्षतः। सुधृष्टमे इति सुऽधृष्टमे। वपुष्ये इति। न। रोदसी इति। पि
ता। यत्। सीं। अभि। रूपैः। अवासयत्॥ सः। वह्निः। पुत्रः। पित्रोः। पवित्रऽवान्। पुनाति। धीरः। भुवनानि।
मायया॥ धेनुं। च। पृश्निं। वृषभं। सुऽरेतसं। विश्वाहा। शुक्रं। पयः। अस्य। धुक्षत॥ अयं। देवानां। अपसां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ अपः। तमः। वः। अनानां। रोदसीइति। विश्वः। शंभुवा। वियायः। म मा। रजसीइति। सुक्रतुः। यया। अजरेभिः

३६ स्कंभनेभिः। सं। आनृचे। नेइति। नृः। गणानेइति। महिनीइति। महिः। अवः। क्षत्रं। द्यावापृथिवीइति। धास

36 थः। बृहत्। येन। अभिः। कृष्टीः। ततनाम। विश्वहा। पनाय्यं। ओजः। अस्मेइति। सं। इन्वतं। ३। किं। ऊंइति।

श्रेष्ठः। किं। यविष्ठः। नृः। आ। अजगन्। किं। ईयते। दूत्यं। कत्। यत्। ऊंचिम। नानां। निंदिमा। चमसं। यः। महाऽ

कुलः। अग्ने। भ्रातः। द्रुणः। इत्। भद्रं। ऊं। दिम। एकं। चमसं। चतुरः। कृणोतन। तत्। वः। देवाः। अब्रुवन्। तत्। वः। व

आ। अगमं। सौधन्वनाः। यदि। एव। करिष्यथ। साकं। देवैः। यज्ञियासः। भविष्यथ। अग्निं। दूतं। प्रति।

यत्। अब्रवीतन। अश्वः। कर्त्वः। रथः। उत। इह। कर्त्वः। धेनुः। कर्त्वा। युवशा। कर्त्वा। द्वा। तानि। भ्रातः। अनु। ३६

© Dharmartha Trust J&K. Digitized by eGangotri

वः। कृत्वी। आ। इमसि। चकृऽवांसः। ऋभवः। तत्। अपृच्छत। क्व। इत्। अभूत्। यः। स्यः। दूतः। नः। आ। अजगन्।
यदा। अवऽअख्यत्। चमसान्। चतुरः। कृतान्। आत्। इत्। त्वष्टा। ग्नासु। अंतः। नि। आनजे॥ हनाम। ए
नान्। इति। त्वष्टा। यत्। अब्रवीत्। चमसं। ये। देवऽपानं। अनिंदिषुः। अन्या। नामानि। कृण्वते। सुते। स
चा। अन्यैः। एनान्। कन्या। नामऽभिः। स्परत्॥ ५॥ इंद्रः। हरी इति। युयुजे। अश्विना। रथं। बृहस्पतिः।
विश्वऽरूपां। उप। आ। अजत। ऋभुः। विऽभ्वा। वाजः। देवान्। अगच्छत। सुऽअपसः। यज्ञियं। भागं। ऐतन॥ प
निः। चर्मणः। गां। अरिणीत। धीतिऽभिः। या। जरंता। युवशा। ता। अकृणोतन। सौधन्वनाः। अश्वा
त्। अश्वं। अतक्षत। युक्त्वा। रथं। उप। देवान्। अयातन। इदं। उदकं। पिबत। इति। अब्रवीतन। इदं। वा। घ। वी

यु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ दि॰ पिबत । मुंजऽनेजनं । सौधन्वनाः । यदि । तत् । नऽइव । हर्यथ । तृतीये । घ । सवने । मादयाध्वै । आपः । भूयिष्ठाः ।
२० इति । एकः । अब्रवीत् । अग्निः । भूयिष्ठः । इति । अन्यः । अब्रवीत् । वधःऽयंतीं । बहुऽभ्यः । प्र । एकः । अब्रवीत् । ऋ-
ता । वदंतः । चमसान् । अपिंशत । श्रोणां । एकः । उदकं । गां । अव । अजति । मांसं । एकः । पिंशति । सूनया । आऽ-
भृतं । आ । निःऽम्रुचः । शकृत् । एकः । अप । अभरत् । किं । स्वित् । पुत्रेभ्यः । पितरौ । उप । आवतुः । १० । उत्ऽवत्ऽसु ।
अस्मै । अकृणोतन । तृणं । निवत्ऽसु । अपः । सुऽअपस्यया । नरः । अगोह्यस्य । यत् । असस्तन । गृहे । तत् । अ-
द्य । इदं । ऋभवः । न । अनु । गच्छथ । संऽमील्य । यत् । भुवना । परिऽअसर्पत । क्व । स्वित् । तात्या । पितरा । वः । आ-
सतुः । अशपत । यः । करस्नं । वः । आऽददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन । सुसुप्वांसः । ऋभ- १२

© Dharmartha Trust J&K. Digitized by eGangotri

वः। तत्। अपरुत्। अगोह्यः। कः। इदं। नः। अबुबुधत्। श्वानं। बस्तः। बोधयितारं। अब्रवीत्। संवत्सरे। इदं।
अद्य। वि। अख्यत। दिवा। यांति। मरुतः। भूम्या। अग्निः। अयं। वातः। अंतरिक्षेण। याति। अद्भिः। याति
। वरुणः। समुद्रैः। युष्मान्। इच्छंतः। शवसः। नपातः। ॥ मा। नः। मित्रः। वरुणः। अर्यमा। आयुः। इंद्रः। ऋभु
क्षाः। मरुतः। परि। ख्यन्। यत्। वाजिनः। देवऽजातस्य। सप्तेः। प्रऽवक्ष्यामः। विदथे। वीर्याणि। यत्। निःऽनि
जा। रेक्णसा। प्रावृतस्य। रातिं। गृभीतां। मुखतः। नयंति। सुऽप्राङ्। अजः। मेम्यत्। विश्वऽरूपः। इंद्रापूष्णोः
। प्रियं। अपि। एति। पाथः। एषः। छागः। पुरः। अश्वेन। वाजिना। पूष्णः। भागः। नीयते। विश्वऽदेव्यः। अभिऽ
प्रियं। यत्। पुरोळाशं। अर्वता। त्वष्टा। इत्। एनं। सौश्रवसाय। जिन्वति। यत्। हविष्यं। ऋतुऽशः। देवऽयानं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰ ३८ त्रिः । मानुषाः । परि । अश्वं । नयंति । अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञं । देवेभ्यः । प्रतिऽवेदयन् । अजः ।
होता । अध्वर्युः । आवयाः । अग्निऽइंधः । ग्रावऽग्राभः । उत । शंस्ता । सुऽविप्रः । तेन । यज्ञेन । सुऽअरंकृतेन ।
सुऽइष्टेन । वक्षणाः । आ । पृणध्वं ॥ ५ ॥ यूपऽव्रस्काः । उत । ये । यूपऽवाहाः । चषालं । ये । अश्वऽयूपाय । तक्ष
38 ति । ये । च । अर्वते । पचनं । संऽभरंति । उतो इति । तेषां । अभिऽगूर्तिः । नः । इन्वतु । उप । प्र । अगात् । सुऽमत् । मे ।
अधायि । मन्म । देवानां । आशाः । उप । वीतऽपृष्ठः । अनु । एनं । विप्राः । ऋषयः । मदंति । देवानां । पुष्टे । चकृम ।
सुऽबंधुं । यत् । वाजिनः । दाम । संऽदानं । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य । यत् । वा । घ । अस्य । प्रऽ
भृतं । आस्ये । तृणं । सर्वा । ता । ते । अपि । देवेषु । अस्तु । यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्व ३८

© Dharmartha Trust J&K. Digitized by eGangotri

रै।स्वऽधितौ।रिप्तं।अस्ति।यत्।हस्तयोः।शमितुः।यत्।नखेषु।॰यत्।ऊवध्यं।उदरस्य।अपऽवाति।यः
।आमस्य।क्रविषः।गंधः।अस्ति।सुऽकृता।तत्।शमितारः।कृण्वंतु।उत।मेधं।शृतऽपाकं।पचंतु॥१०॥यत्
ते।गात्रात्।अग्निना।पच्यमानात्।अभि।शूलं।निऽहतस्य।अवऽधावति।मा।तत्।भूम्यां।आ।श्रि
षत्।मा।तृणेषु।देवेभ्यः।तत्।उशत्ऽभ्यः।रातं।अस्तु।ये।वाजिनं।परिऽपश्यंति।पक्वं।ये।ईं।आहुः।सुर
भिः।निः।हर।इति।ये।च।अर्वतः।मांसऽभिक्षां।उपऽआसते।॰यत्।निऽईक्षणं।मांस्पचन्याः।उखायाः
।या।पात्राणि।यूष्णः।आऽसेचनानि।ऊष्मण्या।अपिऽधाना।चरूणां।अंकाः।सूनाः।परि।भूषंति।अ
श्वं।निःऽक्रमणं।निऽसदनं।विऽवर्तनं।यत्।च।पड्बीशं।अर्वतः।यत्।च।पपौ।यत्।च।घासिं।जघास।

© Dharmartha Trust J&K. Digitized by eGangotri

१.६६ ।मा।त्वा।अग्निः।ध्वनयीत्।धूमगंधिः।मा।उखा।भ्राजंती।अभि।विक्तः।जघ्रिः।इष्टं।वीतं।अभि॥
३९ गूर्त्तं।वषट्कृतं।तं।देवासः।प्रति।गृभ्णंति।अश्वं॥३७॥यत्।अश्वाय।वासः।उपस्तृणंति।अधीवासं
।या।हिरण्यानि।अस्मै।संदानं।अर्वंतं।पड्बीशं।प्रिया।देवेषु।आ।यमयंति।यत्।ते।सादे।महसा।शू॥
39 कृतस्य।पार्ष्ण्या।वा।कशया।वा।तुतोद।स्रुचाऽइव।ता।हविषः।अध्वरेषु।ब्रह्मणा।सूदयामि।चतुः॥
त्रिंशत्।वाजिनः।देवबंधोः।वंक्रीः।अश्वस्य।स्वधितिः।सं।एति।अछिद्रा।गात्रा।वयुना।कृणोत।प॥
रुःऽपरुः।अनुघुष्य।वि।शस्त॥४०॥एकः।त्वष्टुः।अश्वस्य।विऽशस्ता।द्वा।यंतारा।भवतः।तथा।ऋतुः।या।ते।
गात्राणां।ऋतुऽथा।कृणोमि।ताऽता।पिंडानां।प्र।जुहोमि।अग्नौ।मा।त्वा।तपत्।प्रियः।आत्मा।अ ३९

© Dharmartha Trust J&K. Digitized by eGangotri

पिऽयंतं। मा। स्वऽधितिः। तन्वः। आ। तिष्ठिपत्। ते। मा। ते। गृध्नुः। अविऽशस्ता। अतिऽहाय। छिद्रा। गात्राणि।
असिना। मिथु। करिति कः। न। वै। ऊं इति। एतत्। म्रियसे। न। रिष्यसि। देवान्। इत्। एषि। पथिऽभिः। सुऽगेभिः।
हरी इति। ते। युंजा। पृषती इति। अभूतां। उप। अस्थात्। वाजी। धुरि। रासभस्य। सुऽगव्यं। नः। वाजी। सुऽअश्व्यं।
पुंसः। पुत्रान्। उत। विश्वऽपुषं। रयिं। अनागाःऽत्वं। नः। अदितिः। कृणोतु। क्षत्रं। नः। अश्वः। वनतां। हविष्मान्॥
॥१०॥ यत्। अक्रंदः। प्रथमं। आयमानः। उत्ऽयन्। समुद्रात्। उत। वा। पुरीषात्। श्येनस्य। पक्षा। हरिणस्य।
बाहू इति। उप। स्तुत्यं। महि। जातं। ते। अर्वन्। यमेन। दत्तं। त्रितः। एनं। अयुनक्। इंद्रः। एनं। प्रथमः। अधि। अतिष्ठ
त्। गंधर्वः। अस्य। रशनां। अगृभ्णात्। सूरात्। अश्वं। वसवः। निः। अतष्ट। असि। यमः। असि। आदित्यः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प. द्वि
४०
40

वेन्। असि। त्रितः। गुह्येन। व्रतेन। असि। सोमेन। सऽमया। विऽपृक्तः। आहुः। ते। त्रीणि। दिवि। बंधनानि। त्री
णि। ते। आहुः। दिवि। बंधनानि। त्रीणि। अप्ऽसु। त्रीणि। अंतः। समुद्रे। उत। इव। मे। वरुणः। छंत्सि। अर्व
न्। यत्र। ते। आहुः। परमं। जनित्रं। इमा। ते। वाजिन्। अवऽमार्जनानि। इमा। शफानां। सनितुः। निऽधाना।
अत्र। ते। भद्राः। रशनाः। अपश्यं। ऋतस्य। याः। अभिऽरक्षंति। गोपाः। ॥२॥ आत्मानं। ते। मनसा। आरा
त्। अजानां। अवः। दिवा। पतयंतं। पतंगं। शिरः। अपश्यं। पथिऽभिः। सुऽगेभिः। अरेणुऽभिः। जेहमानं। पत
त्रि। अत्र। ते। रूपं। उत्ऽतमं। अपश्यं। जिगीषमाणं। इषः। आ। पदे। गोः। यदा। ते। मर्तः। अनु। भोगं। आन
ट्। आत्। इत्। ग्रसिष्ठः। ओषधीः। अजीगरिति। अनु। त्वा। रथः। अनु। मर्यः। अर्वन्। अनु। गावः। अनु। ४०

© Dharmartha Trust J&K. Digitized by eGangotri

भगः। कनीनां। अनु। व्रातासः। तव। सख्यं। ईयुः। अनु। देवाः। ममिरे। वीर्यं। ते। हिरण्यऽशृंगः। अयः।
अस्य। पादाः। मनःऽजवाः। अवरः। इंद्रः। आसीत्। देवाः। इत्। अस्य। हविःऽअद्यं। आयन्। यः। अर्वंतं। प्र-
थमः। अधिऽअतिष्ठत्। ईर्मऽअंतासः। सिलिकऽमध्यमासः। सं। शूरणासः। दिव्यासः। अत्याः। हंसाःऽ
इव। श्रेणिऽशः। यतंते। यत्। आक्षिषुः। दिव्यं। अज्मं। अश्वाः। १०। तव। शरीरं। पतयिष्णु। अर्वन्। तव। चि-
त्तं। वातःऽइव। ध्रजीमान्। तव। शृंगाणि। विऽस्थिता। पुरुऽत्रा। अरण्येषु। जर्भुराणा। चरंति। ११। शसनं।
वाजी। अर्वा। देवद्रीचा। मनसा। दीध्यानः। अजः। पुरः। नीयते। नाभिः। अस्य। अनु। पश्चात्। क-
वयः। यंति। रेभाः। परमं। यत्। सधऽस्थं। अर्वान्। अछ। पितरं। मातरं। च। अद्य। देवान्। जुष्टऽतमः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰छि॰ हि।गम्याः।अथ।आ।शास्ते।दाशुषे।वार्याणि॥१३॥अस्य।वामस्य।पलितस्य।होतुः।तस्य।भ्राता।
४१ मध्यमः।अस्ति।अश्नः।तृतीयः।भ्राता।घृतऽपृष्ठः।अस्य।अत्र।अपश्यं।विश्पतिं।सप्तऽपुत्रं।सप्त।
युंजंति।रथं।एकऽचक्रं।एकः।अश्वः।वहति।सप्तऽनामा।त्रिऽनाभि।चक्रं।अजरं।अनर्वं।यत्र।इमा
।विश्वा।भुवना।अधि।तस्थुः।इमं।रथं।अधि।ये।सप्त।तस्थुः।सप्तऽचक्रं।सप्त।वहंति।अश्वाः।स
प्त।स्वसारः।अभि।सं।नवंते।यत्र।गवां।निऽहिता।सप्त।नाम।कः।ददर्श।प्रथमं।जायमानं।अस्थ
न्ऽवंतं।यत्।अनस्था।बिभर्ति।भूम्याः।असुः।असृक्।आत्मा।क्व।स्वित्।कः।विद्वांसं।उप।गात्।
प्रष्टुं।एतत्।पाकः।पृच्छामि।मनसा।अविऽजानन्।देवानां।एना।निऽहिता।पदानि।वत्से।बष्कये। ४१

© Dharmartha Trust J&K. Digitized by eGangotri

अधि । सप्त । तंतून् । वि । तत्निरे । कवयः । ओतवै । ऊं इति ॥ ५ ॥ अचिकित्वान् । चिकितुषः । चित् । अत्र ।
कवीन् । पृच्छामि । विद्मने । न । विद्वान् । वि । यः । तस्तंभ । षट् । इमा । रजांसि । अजस्य । रूपे । किं । अपि । स्वि-
त् । एकं । इह । ब्रवीतु । यः । ईं । अंग । वेद । अस्य । वामस्य । निऽहितं । पदं । वेरिति वेः । शीर्ष्णः । क्षीरं । दुह्रते ।
गावः । अस्य । वव्रिं । वसानाः । उदकं । पदा । अपुः । माता । पितरं । ऋते । आ । बभाज । धीती । अग्रे । मन-
सा । सं । हि । जग्मे । सा । बीभत्सुः । गर्भऽरसा । निऽविद्धा । नमस्वंतः । इत् । उपऽवाकं । ईयुः । युक्ता । मा-
ता । आसीत् । धुरि । दक्षिणायाः । अतिष्ठत् । गर्भः । वृजनीषु । अंतः । इति । अमीमेत् । वत्सः । अनु । गां ।
। अपश्यत् । विश्वऽरूप्यं । त्रिषु । योजनेषु । तिस्रः । मातॄः । त्रीन् । पितॄन् । बिभ्रत् । एकः । ऊर्ध्वः । तस्थौ ः

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ नाईं।अवां।ग्लपयंति।मंत्रयंते।दिवः।अमुष्य।पृष्ठे।विश्वऽविदं।वाचं।अविश्वऽमिन्वां॥१०॥द्वाद
५२ शऽअरं।नहि।तत्।जराय।ववर्त्ति।चक्रं।परि।द्यां।ऋतस्य।आ।पुत्राः।अग्ने।मिथुनासः।अत्र।
सप्त।शतानि।विंशतिः।च।तस्थुः।पंचऽपादं।पितरं।द्वादशऽआकृतिं।दिवः।आहुः।परे।अर्द्धे।
52 पुरीषिणं।अथ।इमे।अन्ये।उपरे।विऽचक्षणं।सप्तऽचक्रे।षट्ऽअरे।आहुः।अर्पितं।पंचऽअरे।चक्रे
।परिऽवर्त्तमाने।तस्मिन्।आ।तस्थुः।भुवनानि।विश्वा।तस्य।न।अक्षः।तप्यते।भूरिऽभारः।
सनात्।एव।न।शीर्यते।सऽनाभिः।सऽनेमि।चक्रं।अजरं।विऽवरते।उत्तानायां।दश।युक्ताः।
वहंति।सूर्यस्य।चक्षुः।रजसा।एति।आऽवृतं।तस्मिन्।आर्पिता।भुवनानि।विश्वा।साकंऽ ५२

© Dharmartha Trust J&K. Digitized by eGangotri

जानां।सप्तथं।आहुः।एकऽजं।षट्।इत्।यमाः।ऋषयः।देवऽजाः।इति।तेषां।इष्टानि।विऽहितानि।धाम
ऽशः।स्थात्रे।रेजंते।विऽकृतानि।रूपऽशः।।१५।।स्त्रियः।सतीः।तान्।ऊंइति।मे।पुंसः।आहुः।पश्यत्।
अक्षण्ऽवान्।न।वि।चेतत्।अंधः।कविः।यः।पुत्रः।सः।ईं।आ।चिकेत।यः।ता।विऽजानात्।सः।पि
तुः।पिता।असत्।अवः।परेण।परः।एना।अवरेण।पदा।वत्सं।बिभ्रती।गौः।उत्।अस्थात्।सा।क
द्रीची।कं।स्वित्।अर्द्धं।परा।अगात्।क्व।स्वित्।सूते।नहि।यूथे।अंतरिति।अवः।परेण।पितरं।
यः।अस्य।अनुऽवेद।परः।एना।अवरेण।कविऽयमानः।कः।इह।प्र।वोचत्।देवं।मनः।कुतः।अधि
।प्रऽजातं।ये।अर्वांचः।तान्।ऊंइति।परांचः।आहुः।ये।परांचः।तान्।ऊंइति।अर्वांचः।आहुः।इंद्रः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ चा। या। वक्रऽपुः। सोमा। नानि। धुरा। न। युक्ताः। रजसः। वहंति। द्वा। सुऽपर्णा। सऽयुजा। सखा। या।
४३ समानं। वृक्षं। परि। सस्वजाते इति। तयोः। अन्यः। पिप्पलं। स्वादु। अत्ति। अनश्नन्। अन्यः। अभि। चा
कशीति॥ १७॥ यत्र। सुऽपर्णाः। अमृतस्य। भागं। अनिऽमेषं। विदथा। अभिऽस्वरंति। इनः। विश्वस्य। भु
43 वनस्य। गोपाः। सः। मा। धीरः। पाकं। अत्र। आ। विवेश। यस्मिन्। वृक्षे। मधुऽअदः। सुऽपर्णाः। निऽवि
शंते। सुवते। च। अधि। विश्वे। तस्य। इत्। आहुः। पिप्पलं। स्वादु। अग्रे। तत्। न। उत्। नशत्। यः। पि
तरं। न। वेद। यत्। गायत्रे। अधि। गायत्रं। आऽहितं। त्रैस्तुभात्। वा। त्रैस्तुभं। निःऽअतक्षत। यत्। वा। ज
गत्। जगति। आऽहितं। पदं। ये। इत्। तत्। विदुः। ते। अमृतऽत्वं। आनशुः। गायत्रेण। प्रति। मिमीते। अ ४३

© Dharmartha Trust J&K. Digitized by eGangotri

र्कं। अर्केण। साम। त्रैस्तुना। वाकं। वाकेन। वाकं। द्विऽपदा। चतुःऽपदा। अक्षरेण। मिमते। सप्त। वा

णीः। जगता। सिंधुं। दिवि। अस्तभायत्। रथंऽतरे। सूर्यं। परि। अपश्यत्। गायत्रस्य। संऽइद्धः।

तिस्रः। आहुः। ततः। मह्ना। प्र। रिरिचे। महिऽत्वा॥ २५॥ उप। ह्वये। सुऽदुघां। धेनुं। एतां। सुऽहस्तः। गो

ऽधुक्। उत। दोहत्। एनां। श्रेष्ठं। सवं। सविता। साविषत्। नः। अभिऽइद्धः। घर्मः। तत्। ऊं इति। सु। प्र।

वोचं। हिंऽकृण्वती। वसुऽपत्नी। वसूनां। वत्सं। इछंती। मनसा। अभि। आ। अगात्। दुहां। अश्विऽ

भ्यां। पयः। अघ्न्या। इयं। सा। वर्धतां। महते। सौभगाय। गौः। अमीमेत्। अनु। वत्सं। मिषंतं। मूर्धानं

। हिङ्। अकृणोत्। मातवै। ऊं इति। सृक्काणं। घर्मं। अभि। वावशाना। मिमाति। मायुं। पयते। पयःऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प.द्वि.
५५
55

भिः। अयं। सः। शिङ्क्ते। येन। गौः। अभिऽवृता। मिमाति। मायुं। ध्वसनौ। अधि। श्रिता। सा। चित्तिऽभिः। नि
।हि। चकार। मर्त्यं। विद्युत्। भवंती। प्रति। वव्रिं। औहत। अनत्। शये। तुरऽगातु। जीवं। एजत्। ध्रुवं। म
ध्ये। आ। पस्त्यानां। जीवः। मृतस्य। चरति। स्वधाभिः। अमर्त्यः। मर्त्येन। सऽयोनिः। ३०। अपश्यं। गो
पां। अनिऽपद्यमानं। आ। च। परा। च। पथिऽभिः। चरंतं। सः। सध्रीचीः। सः। विषूचीः। वसानः। आ। वरी
वर्ति। भुवनेषु। अंतरिति। यः। ईं। चकार। न। सः। अस्य। वेद। यः। ईं। ददर्श। हिरुक्। इत्। नु। तस्मात्। सः।
मातुः। योना। परिऽवीतः। अंतः। बहुऽप्रजाः। निःऽऋतिं। आ। विवेश। द्यौः। मे। पिता। जनिता। नाभिः। अ
त्र। बंधुः। मे। माता। पृथिवी। मही। इयं। उत्तानयोः। चम्वोः। योनिः। अंतः। अत्र। पिता। दुहितुः। गर्भं। आ। ५५

© Dharmartha Trust J&K. Digitized by eGangotri

अधात्। पृच्छामि। त्वा। परं। अंतं। पृथिव्याः। पृच्छामि। यत्र। भुवनस्य। नाभिः। पृच्छामि। त्वा। वृष्णः।
अश्वस्य। रेतः। पृच्छामि। वाचः। परमं। विऽओम। इयं। वेदिः। परः। अंतः। पृथिव्याः। अयं। यज्ञः। भु
वनस्य। नाभिः। अयं। सोमः। वृष्णः। अश्वस्य। रेतः। ब्रह्मा। अयं। वाचः। परमं। विऽओम।।२०।। स
प्त। अर्धऽगर्भाः। भुवनस्य। रेतः। विष्णोः। तिष्ठंति। प्रऽदिशा। विऽधर्मणि। ते। धीतिऽभिः। मनसा। ते। वि
पःऽचितः। परि। भुवः। परि। भवंति। विश्वतः। न। वि। जानामि। यत्ऽइव। इदं। अस्मि। निण्यः। संऽनद्धः।
मनसा। चरामि। यदा। मा। आ। अगन्। प्रथमऽजाः। ऋतस्य। आत्। इत्। वाचः। अश्नुवे। भागं। अ
स्याः। अपाङ्। प्राङ्। एति। स्वधया। गृभीतः। अमर्त्यः। मर्त्येन। सऽयोनिः। ता। शश्वंता। विषूचीना।

© Dharmartha Trust J&K. Digitized by eGangotri

फ॰ द्वि॰ विऽयंता। नि। अन्यं। विक्युः। न। नि। चिक्युः। अन्यं॥ ऋचः। अक्षरे। परमे। विऽओमन्। यस्मिन्।
५५ देवाः। अधि। विश्वे। निऽसेदुः। यः। तत्। न। वेद। किं। ऋचा। करिष्यति। ये। इत्। तत्। विदुः। ते। इमे।
सं। आसते॥ सुयवसऽअत्। भगऽवती। हि। भूयाः। अथो इति। वयं। भगऽवंतः। स्याम॥ अद्धि। तृणं।
45 अघ्न्ये। विश्वऽदानीं। पिब। शुद्धं। उदकं। आऽचरंती॥ २३॥ गौरीः। मिमाय। सलिलानि। तक्षती।
एकऽपदी। द्विऽपदी। सा। चतुःऽपदी। अष्टाऽपदी। नवऽपदी। बभूवुषी। सहस्रऽअक्षरा। परमे। व
विऽओमन्। तस्याः। समुद्राः। अधि। वि। क्षरंति। तेन। जीवंति। प्रऽदिशः। चतस्रः॥ ततः। क्षरति। अ
क्षरं। तत्। विश्वं। उप। जीवति॥ शकऽमयं। धूमं। आरात्। अपश्यं। विषुऽवता। परः। एना। अवरेण। ५५

© Dharmartha Trust J&K. Digitized by eGangotri

उक्षाणं । पृश्निं । अपचंत । वीराः । तानि । धर्माणि । प्रथमानि । आसन् ॥ त्रयः । केशिनः । ऋतुऽथा
। वि । चक्षते । संवत्सरे । वपते । एकः । एषां । विश्वं । एकः । अभि । चष्टे । शचीभिः । ध्राजिः । एकस्य । दद्
मिता । दृशे । न । रूपं । चत्वारि । वाक् । परिऽ । पदानि । तानि । विदुः । ब्राह्मणाः । ये । मनीषिणः । गुहा । त्रीणि ।
निऽहिता । न । इंगयंति । तुरीयं । वाचः । मनुष्याः । वदंति ॥ ० आहुः । अथो इति । दिव्यः । सः । सुऽपर्णः ।
गरुत्मान् । एकं । सत् । विप्राः । बहुधा । वदंति । अग्निं । यमं । मातरिश्वानं । आहुः ॥ रश । कृष्णं । निऽ
यानं । हरयः । सुऽपर्णाः । अपः । वसानाः । दिवं । उत् । पतंति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य ।
आत् । इत् । घृतेन । पृथिवी । वि । उद्यते ॥ द्वादश । प्रऽधयः । चक्रं । एकं । त्रीणि । नभ्यानि । कः । ऊं इति ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ ततः।चिकेत।तस्मिन्।साकं।त्रिऽशताः।न।शंकवः।अर्पिताः।षष्टिः।न।चलाऽचलासः।यः।ते।स्त
४६ नः।शशयः।यः।मयःऽभूः।येन।विश्वा।पुष्यसि।वार्याणि।यः।रत्नऽधाः।वसुऽवित्।यः।सुऽद
त्रः।सरस्वति।तं।इह।धातवे।कः।इति।कः। यज्ञेन।यज्ञं।अयजंत।देवाः।तानि।धर्माणि।प्रथमा
नि।आसन्।ते।ह।नाकं।महिमानः।सचंत।यत्र।पूर्वे।साध्याः।संति।देवाः।समानं।एतत्।
उदकं।उत्।च।एति।अव।च।अहऽभिः।भूमिं।पर्जन्याः।जिन्वंति।दिवं।जिन्वंति।अग्नयः।दि
व्यं।सुऽपर्णं।वायसं।बृहंतं।अपां।गर्भं।दर्शतं।ओषधीनां।अभीपतः।वृष्टिऽभिः।तर्पयंतं।
सरस्वंतं।अवसे।जोहवीमि।।२३।।कया।शुभा।सऽवयसः।सऽनीळाः।समान्या।मरुतः। ४६

© Dharmartha Trust J&K. Digitized by eGangotri

सं।मिमिक्षुः।कया।मती।कुतः।आऽइतासः।एते।अर्चंति।शुष्मं।वृषणः।वसुऽया।कस्य।ब्रह्माणि।
जुजुषुः।युवानः।कः।अध्वरे।मरुतः।आ।ववर्त।श्येनान्ऽइव।ध्रजतः।अंतरिक्षे।केन।महा।मनसा।
रीरमाम।कुतः।त्वं।इंद्र।माहिनः।सन्।एकः।यासि।सत्ऽपते।किं।ते।इत्था।सं।पृछसे।संऽअराणः
शुभानैः।वोचेः।तत्।नः।हरिऽवः।यत्।ते।अस्मे इति।ब्रह्माणि।मे।मतयः।शं।सुतासः।शुष्मः।इयर्ति।
प्रऽभृतः।मे।अद्रिः।आ।शासते।प्रति।हर्यंति।उक्था।इमा।हरी इति।वहतः।ता।नः।अछ।अतः।वयं।
अंतमेभिः।युजानाः।स्वऽक्षत्रेभिः।तन्वः।शुंभमानाः।महःऽभिः।एतान्।उप।युज्महे।नु।इंद्र।स्वधां।
अनु।हि।नः।बभूथ।रधा।क्व।स्या।वः।मरुतः।स्वधा।आसीत्।यत्।मां।एकं।संऽअधत्त।अहिऽह

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ स्यै। अहं। हि। उग्रः। तविषः। तुविष्मान्। विश्वस्य। शत्रोः। अनमं। वधःऽस्नैः। भूरि। चकर्थ। युज्येभिः। अ-
५८ स्मे इति। समानेभिः। वृषभ। पौंस्येभिः। भूरीणि। हि। कृणवाम। शविष्ठ। इंद्र। क्रत्वा। मरुतः। यत्। व-
शाम। वधीं। वृत्रं। मरुतः। इंद्रियेण। स्वेन। भामेन। तविषः। बभूवान्। अहं। एताः। मनवे। विश्वऽचं-
97 द्राः। सुऽगाः। अपः। चकर। वज्रऽबाहुः। अनुत्तं। आ। ते। मघऽवन्। नकिः। नु। न। त्वाऽवान्। अस्ति। देव-
ता। विदानः। न। जायमानः। नशते। न। जातः। यानि। करिष्या। कृणुहि। प्रऽवृद्ध। एकस्य। चित्।
मे। विऽभु। अस्तु। ओजः। या। नु। दधृष्वान्। कृणवै। मनीषा॥ ०॥ मरुतः। विदानः। यानि। च्यवं। इंद्रः।
इत्। ईशे। एषां॥ २५॥ अमंदन्। मा। मरुतः। स्तोमः। अत्र। यत्। मे। नरः। श्रुत्यं। ब्रह्म। चक्र। इंद्राय। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

वृष्णे। सुऽमखाय। मह्यं। सख्ये। सखायः। तन्वे। तनूभिः। एव। इत्। एते। प्रति। मा। रोचमानाः। अनेद्यः
। श्रवः। आ। इषः। दधानाः। संऽचक्ष्य। मरुतः। चंद्रऽवर्णाः। अच्छांत। मे। छदयाथ। च। नूनं। कः। नु। अत्र।
मरुतः। ममहे। वः। प्र। यातन। सखीन्। अच्छ। सखायः। मन्मानि। चित्राः। अपिऽवातयंतः। एषां। भूत
। नवेदाः। मे। ऋतानां। आ। यत्। दुवस्यात्। दुवसे। न। कारुः। अस्मान्। चक्रे। मान्यस्य। मेधा। ओ इ
ति। सु। वर्त्त। मरुतः। विप्रं। अच्छ। इमा। ब्रह्माणि। जरिता। वः। अर्चत्। एषः। वः। स्तोमः। मरुतः। इ
यं। गीः। मांदार्यस्य। मान्यस्य। कारोः। आ। इषा। यासीष्ट। तन्वे। वयां। विद्याम। इषं। वृजनं। जी
रऽदानुं॥ २५॥ इतिद्वितीयाष्टकेतृतीयोध्यायः॥ ॥ॐ॥ तन्वगस्त्योमारुतंहिद्वित्रिष्टुबंतंमि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰ त्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुंभे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावजा
४८ यतां सहस्रमेकादशाद्यैंद्री यज्ञायज्ञादशात्रित्रिष्टुबंतं महोष्ठो द्वितीया विराण्न नूनं पंचागस्त्य
48 नैंद्रे हविषि मरुतामुद्यत इंद्रागस्त्ययोः संवाद ऐंद्रस्त्वत्राद्यातृतीया चेंद्रवाक्यं चतुर्थी चादौ बृहतीति ती
सोनुष्टुभः प्रतिवःष्णोरुतं तु चतस्रोंत्या मरुत्वतीयाभित्रस्तृचं गायत्रं गायत्सप्तोना त्वं राजा दश
मास्तिषष्ठ्यानुष्टुभं तु त्रिष्टुबंतं त्वा घास्कंधोग्नीवीवामस्तिन आ चर्षणिप्राः पंच यद्वस्या पूर्वीः ष
ड्ना यापत्यो लोपामुद्राया अगस्त्यस्य च द्वयाभ्यां रत्यर्थं संवादं श्रुत्वांतेवासी ब्रह्मचार्यंत्ये
बृहत्यादी अपश्यत् पृथुर्दशाश्विनं वैकद्रुनवाभ्यादिदमष्टौ पश्चंत्या त्रिष्टुभौ तं युंजाथां षट्॥१३॥ ४८

© Dharmartha Trust J&K. Digitized by eGangotri

हरिःऽॐ॥तत्।नु।वोचाम।रभसाय।जन्मने।पूर्वं।महिऽत्वं।वृषभस्य।केतवे।ऐधाऽइव।यामन्।
मरुतः।तुविऽस्वनः।युधाऽइव।शक्राः।तविषाणि।कर्त्तन।नित्यं।न।सूनुं।मधु।बिभ्रतः।उप।
क्रीळंति।क्रीळाः।विदथेषु।घृष्वयः।नक्षंति।रुद्राः।अवसा।नमस्विनं।न।मर्धंति।स्वऽतवसः।
हविःऽकृतं।यस्मै।ऊमाः।सः।अमर्ताः।अराः।तत।रायः।पोषं।च।हविषा।ददाशुषे।उक्षंति।अस्मै।
मरुतः।हिताःऽइव।पुरु।रजांसि।पयसा।मयःऽभुवः।आ।ये।रजांसि।तविषीभिः।अव्यत।प्र।
वः।एवासः।स्वऽयतासः।अध्रजन्।भयंते।विश्वा।भुवनानि।हर्म्या।चित्रः।वः।यामः।प्रऽयता
सु।ऋष्टिषु।यत्।त्वेषऽयामाः।नदयंत।पर्वतान्।दिवः।वा।पृष्ठं।नर्याः।अचुच्यवुः।विश्वः।वः।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰हिं ऽमन्।भयते।वनस्पतिः।रथीयंतीऽइव।प्र।जिहीते।ओषधिः॥३॥युयं।नः।उग्राः।मरुतः।
४९ सुऽचेतुना।अरिष्टऽग्रामाः।सुऽमतिं।पिपर्तन।यत्र।वः।दिद्युत्।रदति।क्रिविःऽदती।रिणाति।
पश्वः।सुधिताऽइव।बर्हणा।प्र।स्कंभऽदेष्णाः।अनवभ्रऽराधसः।अलातृणासः।विदथेषु।
49 सुऽस्तुताः।अर्चंति।अर्कं।मदिरस्य।पीतये।विदुः।वीरस्य।प्रथमानि।पौंस्या।शतभुजिऽ
भिः।तं।अभिऽह्रुतेः।अघात्।पूःऽभिः।रक्षत।मरुतः।यं।आवत।जनं।यं।उग्राः।तवसः।विऽ
रप्शिनः।पाथन।शंसात्।तनयस्य।पुष्टिषु।विश्वानि।भद्रा।मरुतः।रथेषु।वः।मिथस्पृध्या
ऽइव।तविषाणि।आऽहिता।अंसेषु।आ।वः।प्रऽपथेषु।खादयः।अक्षः।वः।चक्रा।समया। ४९

© Dharmartha Trust J&K. Digitized by eGangotri

वि।व्रता।भूरीणि।भद्रा।नर्येषु।बाहुषु।वक्षःऽसु।रुक्माः।रभसासः।अंजयः।अंसेषु।एताः।
पविषु।क्षुराः।अधि।वयः।न।पक्षान्।वि।अनु।श्रियः।धिरे।।१०।।महांतः।मन्हा।विऽभ्वः।वि
ऽभूतयः।दूरेऽदृशः।ये।दिव्याःऽइव।स्तृऽभिः।मंद्राः।सुऽजिह्वाः।स्वरितारः।आसऽभिः।संऽमिश्लाः।
मरुतः।इंद्रे।मरुतः।परिऽस्तुभः।तत्।वः।सुऽजाताः।महिऽत्वनं।दीर्घं।वः।दात्रं।अदितेःऽइव।व्रतं।इंद्रः।चन।त्य
जसा।वि।ह्रुणाति।तत्।जनाय।यस्मै।सुऽकृते।अराध्वं।तत्।वः।जामिऽत्वं।मरुतः।परे।युगे।पुरु।
यत्।शंसं।अमृतासः।आवत।अया।धिया।मनवे।श्रुष्टिं।आव्य।साकं।नरः।दंसनैः।आ।चिकि
त्रिरे।येन।दीर्घं।मरुतः।शूशवाम।युष्माकेन।परीणसा।तुरासः।आ।यत्।ततनन्।वृजने।जना

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ स:। एभि:। यज्ञेभि:। तन्। अभि। इष्टिं। अश्यां। ०। ऊ३। सहस्रं। नः। इंद्राः। ऊतयः। नः। सहस्रं। इषः। गृ हरिवः।
५० तेऽतमाः। सहस्रं। रायः। मादयध्यै। सहस्रिणः। उप। नः। यंतु। वाजाः। आ। नः। अवःऽभि:। मरुतः।
यांतु। अच्छ। ज्येष्ठेभि:। वा। बृहत्ऽदिवैः। सुऽमायाः। अध। यत्। एषां। निऽयुतः। परमाः। समुद्रस्य।
चित्। धनयंत। पारे। मिम्यक्ष। येषु। सुऽधिता। घृता। ची। हिरण्यऽनिर्निक्। उपरा। न। ऋष्टिः। गुहा।
चरंती। मनुषः। न। योषा। सभाऽवती। विदथ्याऽइव। सं। वाक्। परा। शुभ्राः। अयासः। यव्या। सा
धारण्याऽइव। मरुतः। मिमिक्षुः। न। रोदसी इति। अप। नुदंत। घोराः। जुषंत। वृधं। सख्याय। दे
वाः। जोषत्। यत्। ईं। असुर्या। सचध्यै। विसितऽस्तुका। रोदसी। नृऽमनाः। आ। सूर्याऽइव। वि ५०

© Dharmartha Trust J&K. Digitized by eGangotri

धनः।रथं।गात्।त्वेषऽप्रतीका।नभसः।[illegible]।न।ईत्या।६।आ।अस्थापयंत।युवतिं।युवानः।शुभे
।निऽमिश्लां।विदथेषु।पज्रां।अर्कः।यत्।वः।मरुतः।हविष्मान्।गायत्।गाथं।सुतऽसोमः।दुवस्य
न्।प्र।तं।विवक्मि।वक्म्यः।यः।एषां।मरुतां।महिमा।सत्यः।अस्ति।सचा।यत्।ईं।वृषऽमनाः।
अहंऽयुः।स्थिरा।चित्।जनीः।वहते।सुऽभागाः।पांति।मित्रावरुणौ।अवद्यात्।चयते।ईं।अर्य
मो इति।अप्रऽशस्तान्।उत।च्यवंते।अच्युता।ध्रुवाणि।ववृधे।ईं।मरुतः।दातिऽवाराः।नहि।नु।वः
।मरुतः।अंति।अस्मे इति।आरात्तात्।चित्।शवसः।अंतं।आपुः।ते।धृष्णुना।शवसा।शुशुऽवां
सः।अर्णः।न।द्वेषः।धृषता।परि।स्थुः।वयं।अद्य।इंद्रस्य।प्रेष्ठाः।वयं।श्वः।वोचेमहि।संऽमर्ये।वयं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ पुरः। माहि।चानः। अन्तु। धूर्नातन्। नः। ऋभुक्षाः। नरां। अनु। स्यात्। ०॥ प॥ यज्ञाऽयज्ञा। वः। समना। तु
५१ तुर्वणिः। धियंऽधियं। वः। देवऽयाः। ऊं इति। दधिध्वे। आ। वः। अर्वाचः। सुविताय। रोदस्योः। महे। ववृत्यां।
51 अवसे। सुवृक्तिऽभिः। वव्रासः। न। ये। स्वऽजाः। स्वऽतवसः। इषं। स्वः। अभिऽजायंत। धूतयः। सहस्रि
यासः। अपां। न। ऊर्मयः। आसा। गावः। वंद्यासः। न। उक्षणः। सोमासः। न। ये। सुताः। तृप्तऽअंशवः।
हृत्ऽसु। पीतासः। दुवसः। न। आसते। आ। एषां। अंसेषु। रंभिणीऽइव। ररभे। हस्तेषु। खादिः। च।
कृतिः। च। सं। दधे। अव। स्वऽयुक्ताः। दिवः। आ। वृथा। ययुः। अमर्त्याः। कशया। चोदत। त्मना। अरे
णवः। तुविऽजाताः। अचुच्यवुः। दृळ्हानि। चित्। मरुतः। भ्राजत्ऽऋष्टयः। कः। वः। अंतः। मरुतः। ५३

© Dharmartha Trust J&K. Digitized by eGangotri

ऋष्टिऽविद्युतः। रेजति। त्मना। हन्वाऽइव। जिह्वया। धन्वऽच्युतः। इषां। न। यामनि। पुरुऽप्रैषाः। अह

न्यः। न। एतशः।५। क्व। स्वित्। अस्य। रजसः। महः। परं। क्व। अवरं। मरुतः। यस्मिन्। आऽयय। य

त्। च्यवयथ। विथुराःऽइव। संऽहितं। वि। अद्रिणा। पतथ। त्वेषं। अर्णवं। सातिः। न। वः। अमऽवती। स्वः

ऽवती। त्वेषा। विऽपाका। मरुतः। पिपिष्वती। भद्रा। वः। रातिः। पृणतः। न। दक्षिणा। पृथुऽज्रयी। असुर्याऽ

इव। जंजती। प्रति। स्तोभंति। सिंधवः। पविऽभ्यः। यत्। अभ्रियां। वाचं। उत्ऽईरयंति। अव। स्मयंत।

विऽद्युतः। पृथिव्यां। यदि। घृतं। मरुतः। प्रुष्णुवंति। असूत। पृश्निः। महते। रणाय। त्वेषं। अयासां।

मरुतां। अनीकं। ते। सप्सरासः। अजनयंत। अभ्वं। आत्। इत्। स्वधां। इषिरां। परि। अपश्यन्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ब्धि ।०।७।मह्रः।[illegible]चित्रा।त्वां।इंद्र।यतः।एता।न्।महः।चित्र।अस्ति।त्यज।सः।वरूता।सः।नः
५२ ।वेधः।मरुतां।चिकित्वान्।सुम्ना।वनुष्व।तव।हि।प्रेष्ठा।अयुज्रन्।ते।इंद्र।विश्वऽकृष्टीः।विदाना।सः
।निःऽसिधः।मर्त्यऽत्रा।मरुतां।पृत्सुतिः।हासमाना।स्वःऽमीळ्हस्य।प्रऽधनस्य।साता।अस्य।क्र
52 साता।इंद्र।ऋष्टिः।अस्मेइति।सनेमि।अभ्वं।मरुतः।जुनंति।अग्निः।चित्।हि।स्म।अतसा।शुशु
कान्।आपः।न।द्वीपं।दधति।प्रयांसि।त्वं।तु।नः।इंद्र।तं।रयिं।दाः।ओजिष्ठया।दक्षिणयाऽइव।
राति।स्तुतः।च।याः।ते।चकनंत।वायोः।स्तनं।न।मध्वः।पीपयंत।वाजैः।त्वेइति।रायः।इंद्र।तोशऽ
तमाः।प्रऽनेतारः।कस्य।चित्।ऋतऽयोः।ते।सु।नः।मरुतः।मृळयंतु।ये।स्म।पुरा।गातुयंतिऽइव। ५२

© Dharmartha Trust J&K. Digitized by eGangotri

देवाः॥५॥प्रति।प्र।याहि।इंद्र।मीळ्हुषः।नृ न।महः।पार्थिवे।सदने।यतस्व॥६॥पृथुऽबुध्नासः।एतोः

तीर्थे।न।अर्यः।पौंस्यानि।तस्थुः।प्रति।घोराणां।एतानां।अयासां।मरुतां।शृण्वे।आऽयतां।

उपब्दिः।यः।मर्त्यं।पृतन्यऽयंतं।ऊमैः।ऋणऽवानं।न।पतयंत।सर्गैः।त्वं।मानेभ्यः।इंद्र।विश्वऽज

न्या।रद।मरुत्ऽभिः।[illegible]।शुरुधः।गोऽअग्राः।स्तवानेभिः।स्तवसे।देव।देवैः॥८॥९॥न।नूनं।अ

स्ति।नो इति।श्वः।कः।तत्।वेद।यत्।अद्भुतं।अन्यस्य।चित्तं।अभि।संऽचरेण्यं।उत।आऽधीतं

स ।वि।नश्यति।किं।नः।इंद्र।जिघांससि।भ्रातरः।मरुतः।तव।तेभिः।कल्पस्व।साधुऽया।मा।नः।

संऽअरणे।वधीः।किं।नः।भ्रातः।अगस्त्य।सखा।सन्।अति।मन्यसे।विद्म।हि।ते।यथा।म

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ ५३ नः। अस्मभ्यं। इन्द्र। न। आ। दिदृक्षसि। अरं। कृण्वन्तु। वेदिं। सं। अग्निं। इन्धतां। पुरः। तत्र। अमृतस्य। चे-
तनं। यज्ञं। ते। तनवावहै। त्वं। ईशिषे। वसुऽपते। वसूनां। त्वं। मित्राणां। मित्रऽपते। धेष्ठः। इन्द्र। त्वं।
मरुत्ऽभिः। सं। वदस्व। अध। प्र। अशान। ऋतुऽथा। हवींषि॥३०॥ प्रति। वः। एना। नमसा। अ-
हं। आ। इमि। सुऽउक्तेन। भिक्षे। सुऽमतिं। तुराणां। रराणता। मरुतः। वेद्याभिः। नि। हेळः। धत्त। वि।
मुचध्वं। अश्वान्॥१॥ नमस्वान्। हृदा। तष्टः। मनसा। धायि। देवाः। उप। ईं। आ। यात। मनसा।
जुषाणाः। यूयं। हि। स्थ। नमसः। इत्। वृधासः। स्तुतासः। नः। मरुतः। मृळयन्तु। उत। स्तुतः। मघऽवा।
शंऽभविष्ठः। ऊर्ध्वा। नः। सन्तु। कोम्या। वनानि। अहानि। विश्वा। मरुतः। जिगीषा। अस्मात्। अहं। ५३

53

© Dharmartha Trust J&K. Digitized by eGangotri

नविषान्।ईषमाणाः।इंद्रान्।मियाः।मरुतः।रेजमानाः।युष्मभ्यं।हव्या।निऽशितानि।आसन्।ता
नि।आरे।वरुणम्।मृळत।नः।येन।मानाः।सः।चितयंत।उस्राः।विऽउ।शिप्रा।शवसा।शम्भ्वतीनां।सः
।नः।मरुत्ऽभिः।वृषभ।श्रवः।धाः।उग्रः।उग्रेभिः।स्थविरः।सहःऽदाः।त्वं।पाहि।सहीयसः।नृन् इंद्र।
न्।भव।मरुत्ऽभिः।अवयातऽहेळाः।सुऽप्रकेतेभिः।ससहिः।दधानः।७।१३॥चित्रः।वः।अस्तु।
यामः।चित्रः।ऊती।सुऽदानवः।मरुतः।अहिऽभानवः।आरे।सा।वः।सुऽदानवः।मरुतः।ऋंज
ती।शरुः।आरे।अश्मा।यं।अस्यथ।तृणऽस्कंदस्य।नु।विशः।परि।वृंक्त।सुऽदानवः।ऊर्ध्वान्।नः। न्
कर्त।जीवसे॥१२॥गायत्।साम।नभन्यं।यथा।वेः।अर्चा।तत्।ववृधानं।स्वःऽवत्।गावः।
म

© Dharmartha Trust J&K. Digitized by eGangotri

पा·द्विं धेनवः। बर्हिषि। अदब्धाः। आ। यत्। सद्मानं। दिव्यं। विवासान्। अर्चन्तु। वृषा। वृषऽभिः। स्वऽदु
५४ हव्यैः। मृगः। न। अश्नः। अति। यत्। जुगुर्यात्। प्र। मंदयुः। मनां। गूर्त। होता। भरते। मर्यः। मिथु
ना। यजत्रः। नक्षत्। होता। परि। सद्म। मिता। यन्। भरत्। गर्भं। आ। शरदः। पृथिव्याः। क्रंदत्। अ
श्वः। नयमानः। रुवत्। गौः। अंतः। दूतः। न। रोदसी इति। चरत्। वाक्। ता। कर्म। अवऽतरा। अस्मै।
प्रऽच्यौत्ना। नि। देवऽयंतः। भरंते। जुजोषत्। इंद्रः। दस्मऽवर्चाः। नासत्याऽइव। सुग्म्यः। रथेऽस्थाः। तं।
ऊं इति। स्तुहि। इंद्रं। यः। ह। सत्वा। यः। शूरः। मघऽवा। रथेऽस्थाः। प्रतीचः। चित्। योधीयान्। वृषण्ऽ यः
वान्। ववव्रुषः। चित्। तमसः। विऽहंता॥ ३॥ प्र। यत्। इत्था। महिना। नृऽभ्यः। अस्ति। अरं। रोदसी ५४

© Dharmartha Trust J&K. Digitized by eGangotri

वि

इति। कक्ष्ये३ इति। न। अस्मै। सं। विव्ये। इंद्रः। वृजनं। न। भूम। भर्ति। स्वधाऽवान्। ओपशंऽइव। द्यां। सम

त्ऽसु। त्वा। शूर। सतां। उराणं। प्रपथिन्ऽतमं। परिऽतंसयध्यै। सऽजोषसः। इंद्रं। मदे। क्षोणीः। सूरिं।

चित्। ये। अनुऽमदंति। वाजैः। एव। हि। ते। शं। सवना। समुद्रे। आपः। यत्। ते। आसु। मदंति। देवीः। वि

श्वा। ते। अनु। जोष्या। भूत्। गौः। सूरीन्। चित्। यदि। धिषा। वेषि। जनान्। असाम। यथा। सुऽसखा

यः। एन। सुऽअभिष्टयः। नरां। न। शंसैः। असत्। यथा। [illegible]नः। इंद्रः। वंदनेऽस्थाः। तुरः। न। कर्म।

नयमानः। उक्था। विऽस्पर्धसः। नरां। न। शंसैः। अस्माक। असत्। इंद्रः। वज्रऽहस्तः। मित्रऽयुवः। न।

पूःऽपतिं। सुऽशिष्टौ। मध्यऽयुवः। उप। शिक्षंति। यज्ञैः। १०। यज्ञः। हि। स्म। इंद्रं। कः। चित्। ऋंधन्। जु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ हुराणः। चित्। मनसा। परिऽयन्। तीर्थे। न। अच्छ। ततृषाणं। ओकः। दीर्घः। न। सिध्रं। आ। कृणोति।
५५ अध्वा। मो इति। सु। नः। इंद्र। अत्र। पूतः। सुऽदेवैः। अस्ति। हि। स्म। ते। शुष्मिन्। अवऽयाः। महः। चित्।
यस्य। मीळ्हुषः। भव्याः। हविष्मतः। मरुतः। वंदते। गीः। एषः। स्तोमः। इंद्र। तुभ्यं। अस्मे इति। एतेन।
गातुं। हरिऽवः। विदः। नः। आ। नः। ववृत्याः। सुविताय। देव॥ २५॥ त्वं। राजा। इंद्र। ये। च। देवाः। र
क्ष। नॄन्। पाहि। असुर। त्वं। अस्मान्। त्वं। सत्ऽपतिः। मघऽवा। नः। तरुत्रः। त्वं। सत्यः। वसवानः।
सहःऽदाः। दनः। विशः। इंद्र। मृध्रऽवाचः। सप्त। यत्। पुरः। शर्म। शारदीः। दर्त्। ऋणोः। अपः। अ
नवद्या। अर्णाः। यूने। वृत्रं। पुरुऽकुत्साय। रंधीः। अजाः। वृतः। इंद्र। शूरऽपत्नीः। द्यां। च। येभिः। पु ५५

© Dharmartha Trust J&K. Digitized by eGangotri

स्रः । हृता । न्ऽनं । रक्षोऽइति । अग्निं । अशुषं । तूर्वयाणं । सिंहः । न । दमे । अपांसि । वस्तोः । शेषन् । नु । ते ।
इंद्र । सस्मिन् । योनौ । प्रऽशस्तये । पवीरवस्य । मन्हा । सृजत् । अर्णांसि । अव । यत् । युधा । गाः
। तिष्ठत् । हरीऽइति । धृषता । मृष्ट । वाजान् । वह । कुत्सं । इंद्र । यस्मिन् । चाकन् । स्यूमन्यूऽइति । ऋ-
ज्रा । वातस्य । अश्वा । प्र । सूरः । चक्रं । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रऽबाहुः
॥३६॥ जघन्वान् । इंद्र । मित्रेरून् । चोदऽप्रवृद्धः । हरिऽवः । अदाशून् । प्र । ये । पश्यन् । अर्यमणं । स-
चा । आयोः । त्वया । शूर्ताः । वहमानाः । अपत्यं । रपत् । कविः । इंद्र । अर्कऽसातौ । क्षां । दासाय । उ-
पऽबर्हणीं । करिति कः । करत् । तिस्रः । मघऽवा । दानुऽचित्राः । नि । दुर्योणे । कुयवाचं । मृधि ।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.द्वि. श्नेता । सना । ता । ते । इंद्र । नव्याः । आ । अगुः । सहः । नभः । अविऽरणाय । पूर्वीः । भिनत् । पुरः । न । भि
५८ दः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥ त्वं । धुनिः । इंद्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्र
58 वंतीः । प्र । यत् । समुद्रं । अति । शूर । पर्षि । पारय । तुर्वशं । यदुं । स्वस्ति ॥ त्वं । अस्माकं । इंद्र । विश्वध । स्याः
। अवृकऽतमः । नरां । नृऽपाता । सः । नः । विश्वासां । स्पृधां । सहःऽदाः ॥ ११ ॥ ३ ॥ मत्सि । अपायि । ते ।
महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः । वृषा । ते । वृष्णे । इंदुः । वाजी । सहस्रऽसातमः । आ । नः ।
ते । गंतु । मत्सरः । वृषा । मदः । वरेण्यः । सहऽवान् । इंद्र । सानसिः । पृतनाषाट् । अमर्त्यः ॥ त्वं । हि । शूर
रः । सनिता । चोदयः । मनुषः । रथं । सहऽवान् । दस्युं । अव्रतं । ओषः । पात्रं । न । शोचिषा । मुषाय । ५८

© Dharmartha Trust J&K. Digitized by eGangotri

सूर्यं।कवे।चक्रं।ईशानः।ओजसा।वह।शुष्णाय।वधं।कुत्सं।वातस्य।अश्वैः।०वृत्रऽघ्ना।वरि
वःऽविदा।मंसीष्ठाः।अश्वऽसातमः।यथा।पूर्वेभ्यः।जरितृऽभ्यः।इंद्र।मयःऽइव।आपः।न।तृष्य
ते।बभूथ।तां।अनु।त्वा।निऽविदं।जोहवीमि।वा।१८।मत्सि।नः।वस्यःऽइष्टये।इंद्रं।इंदोऽइति।
वृषा।आ।विश।ऋघायमाणः।इन्वसि।शत्रुं।अंति।न।विंदसि।तस्मिन्।आ।वेशय।गिरः।
०अनु।स्वधा।यं।उप्यते।यवं।न।चर्कृषत्।वृषा।यस्य।विश्वानि।हस्तयोः।पंच।क्षितीनां।
वसु।स्पाशयस्व।यः।अस्मऽध्रुक्।दिव्याऽइव।अशनिः।जहि।असुन्वंतं।समं।जहि।दुःऽनशं।
यः।न।ते।मयः।अस्मभ्यं।अस्य।वेदनं।दद्धि।सूरिः।चित्।ओहते।आवः।यस्य।द्विऽबर्हसः।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ केषु।सानुषक्।असत्।आ।जौ।इंद्र।स्य।इंदो इति।पा।१७।।आ।चर्षणिऽप्राः।वृषभः।जनानां।रा
५७ जा।कृष्टीनां।पुरुऽहूतः।इंद्रः।स्तुतः।श्रवस्यन्।अवसा।उप।मद्रिक्।युक्त्वा।हरी इति।वृष
णा।आ।याहि।अर्वाङ्।ये।ते।वृषणः।वृषभासः।इंद्र।ब्रह्मऽयुजः।वृषऽरथासः।अत्याः।ता
न्।आ।तिष्ठ।तेभिः।आ।याहि।अर्वाङ्।हवामहे।त्वा।सुते।[illegible]।इंद्र।सोमे।आ।तिष्ठ।
रथं।वृषणं।वृषा।ते।सुतः।सोमः।परिऽसिक्ता।मधूनि।युक्त्वा।वृषऽभ्यां।वृषभ।क्षिती
नां।हरिऽभ्यां।याहि।प्रऽवता।उप।मद्रिक्।अयं।यज्ञः।देवऽयाः।अयं।मियेधः।इमा।ब्रह्मा
णि।अयं।इंद्र।सोमः।स्तीर्णं।बर्हिः।आ।तु।शक्र।प्र।याहि।पिब।निऽसद्य।वि।मुच।हरी इ ५७

© Dharmartha Trust J&K. Digitized by eGangotri

ता।इह।आऽइता।स्तुषे।स्तुनः।इंद्र।याहि।अर्वाङ्।उप।ब्रह्माणि।मान्यस्य।कारोः।विद्याम।वस्तोः।
अवसा।गृणंतः।गाऽरणाय।नरा।हास्या।ते।इंद्र।श्रुष्टिः।अस्ति।यया।बभूथ।जरितृभ्यः।ऊती।
मा।नः।कामं।महयंतं।आ।धक्।विश्वा।ते।अश्यां।परि।आपः।आयोः।नाघ।राजा।इंद्र।आ
दभत्।नः।या।नु।स्वसारः।कृणवंत।योनौ।अपः।चित्।अस्मै।सुऽतुकाः।अवेषन्।गामत्
त्।नः।इंद्रः।सख्या।वयः।च।प्रजेनी।नृऽभिः।इंद्र।पृत्ऽसु।शूरः।ओता।हवी।नाधमानस्य।कारोः। सु॰
ग्रऽभर्ता।रथं।दाशुषः।उपाके।उद्यंता।गिरः।यदि।च।त्मना।भूत्।एव।नृऽभिः।इंद्र।सुऽश्रव
स्या।प्रऽखादः।पृक्षः।अभि।मित्रिणः।भूत्।सऽमर्ये।इषः।स्तवते।विऽवाचि।सत्राऽकरः।

२९

© Dharmartha Trust J&K. Digitized by eGangotri

वयं।

प.हि. यजमानस्य।शंसः।त्वया।मघऽवन्।इंद्र।शत्रून्।अभि।स्याम।महतः।मन्यमानान्।त्वं।त्राता।
५८ त्वं।ऊं इति।नः।वृधे।भूः।०।२४।पूर्वीः।अहं।शरदः।शश्रमाणा।दोषाः।वस्तोः।उषसः।जरयं
58 तीः।मिनाति।श्रियं।जरिमा।तनूनां।अपि।ऊं इति।नु।पत्नीः।वृषणः।जगम्युः।ये।[illegible]।चित्।
हि।पूर्वे।ऋतऽसापः।आसन्।साकं।देवेभिः।अवदन्।ऋतानि।ते।चित्।अव।असुः।नहि।
अंतं।आपुः।सं।०।वृषऽभिः।जगम्युः।न।मृषा।श्रांतं।यत्।अवंति।देवाः।विश्वाः।इत्।स्पृधः।
।अभि।अश्नवाव।जयाव।इत्।अत्र।शतऽनीथं।आजिं।यत्।सम्यंचा।मिथुनौ।अभि।अजा
वा।नदस्य।मा।रुधतः।कामः।आ।अगन्।इतः।आऽजातः।अमुतः।कुतः।चित्।लोपामुद्रा। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

वृषणं। निः। अरिणाति। धीरः। अधीराः। धयन्ति। अश्वसंतं। इमं। नु। सोमं। अंतितः। हृत्सु। पीतं। उप।
ब्रुवे। यत्। ईं। आगः। चकृम। तत्। सु। मृळतु। पुलुऽकामः। हि। मर्त्यः। अगस्त्यः। खनमानः। खनि
त्रैः। प्रऽजां। अपत्यं। बलं। इच्छमानः। उभौ। वर्णौ। ऋषिः। उग्रः। पुपोष। सत्याः। देवेषु। आऽशिषः।
जगाम। आ। रत्ना। युवोः। रजांसि। सुऽयमासः। अश्वाः। रथः। यत्। वां। परि। अर्णांसि। दीयत्।
हिरण्ययाः। वां। पवयः। प्रुषायन्। मध्वः। पिबंतौ। उषसः। सचेथे इति। युवं। अस्य। अव। न
क्षथः। यत्। विऽपत्मनः। नर्यस्य। प्रऽयज्योः। स्वसा। यत्। वां। विश्वगूर्ती इति विश्वऽगूर्ती। भ
रति। वाजाय। ईट्टे। मधुऽपौ। इषा। युवं। पयः। उस्रियायां। अधत्तं। पक्वं। आमायां। अव। पू

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ र्व्यं। गोः। अंतः। यत्। वनिनः। वां। ऋतप्सू इत्यृतऽप्सू। ह्वारः। न। शुचिः। यजते। हविष्मान्। युवं।
५९ ह। घर्मं। मधुऽमंतं। अत्रये। अपः। न। क्षोदः। अवृणीतं। एषे। तत्। वां। नरौ। अश्विना। पश्वःऽइष्टिः।
रथ्याऽइव। चक्रा। प्रति। यंति। मध्वः। आ। वां। दानाय। ववृतीय। दस्रा। गोः। ओहेन। तौग्र्यः। न
59 । जिव्रिः। अपः। क्षोणी इति। सचते। माहिना। वां। जूर्णः। वां। अक्षुः। अंहसः। यजत्रा ॥ २३ ॥ नि।
यत्। युवेथे इति। निऽयुतः। सुदानू इति सुऽदानू। उप। स्वधाभिः। सृजथः। पुरंऽधिं। प्रेषत्। वे-
षत्। वातः। न। सूरिः। आ। महे। ददे। सुऽव्रतः। न। वाजं। वयं। चित्। हि। वां। जरितारः। सत्याः। वि-
पन्यामहे। वि। पणिः। हितऽवान्। अध। चित्। हि। स्म। अश्विनौ। अनिंद्या। पाथः। हि। स्म। वृ- ५९

© Dharmartha Trust J&K. Digitized by eGangotri

षणौ। अत्तिऽदेवं। युवं। चित्ता। हि। स्मः। अश्विनौ। अनु। द्यून्। विऽरुद्रस्य। प्रऽस्रवणस्य। सातौ। अग
स्त्यः। नरां। नृषु। प्रऽशस्तः। काराधुनीऽइव। चितयत्। सहस्रैः। प्रायत्। वहेथे इति। मिह्ना। रथस्य।
प्र। स्यंद्रा। याथः। मनुषः। न। होता। धत्तं। सूरिऽभ्यः। उत। वा। सुऽअश्व्यं। नासत्या। रयिऽसाचः। स्या
म। तं। वां। रथं। वयं। अद्य। हुवेम। स्तोमैः। अश्विना। सुविताय। नव्यं। अरिष्टऽनेमिं। परि। द्यां। इया
नं। गा। रथ्या। कत्। ऊं इति। प्रेष्ठौ। इषां। रयीणां। अध्वर्यन्ता। यत्। उत्ऽनिनीथः। अपां। अयं। वां। यज्ञः।
अकृत। प्रऽशस्तिं। वसुधिती इति वसुऽधिती। अवितारा। जनानां। आ। वां। अश्वासः। शुचयः।
पयःऽपाः। वातऽरंहसः। दिव्यासः। अत्याः। मनःऽजुवः। वृषणः। वीतऽपृष्ठाः। आ। इह। स्वऽराजः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ छि अश्विना। वहेतु॥ अवनिः। नाम्रवत्वा। नासत्यऽवंधुरः। सुविताय। गम्याः। वक्षः। स्थाता। रा। मुनसः।
७ धि नवीयान्। अहं। पूर्व्यः। यजतः। अस्य। आयुः। इहऽइह। जाता। सं। अवा। वशीतां। अरेपसा। तन्वा। नामऽ
60 भिः। स्वैः। जिष्णुः। वां। अन्यः। सुऽमखस्य। सूरिः। दिवः। अन्यः। सुऽभगः। पुत्रः। ऊहे। प्र। वां। निऽचेरुः
कु ककुहः। वशान्। अनु। पिशंगऽरूपः। सदनानि। गम्याः। हरी इति। अन्यस्य। पीपयंत। वाजैः। म
थ्ना। रजांसि। अश्विना। वि। घोषैः॥ प्र। वां। शरत्ऽवान्। वृषभः। न। निःऽसाट्। पूर्वीः। इषः। चरति। मध्वः। इ वां॰ः
ष्णन्। एवैः। अन्यस्य। पीपयंत। वाजैः। वेषंतीः। ऊर्ध्वाः। नद्यः। नः। आ। अगुः। असर्जि। वां। स्थ
विरा। वेधसा। गीः। बाळ्हे। अश्विना। त्रेधा। क्षरंती। उपऽस्तुतौ। अवतं। नाधमानं। यामन्। अ ६०

© Dharmartha Trust J&K. Digitized by eGangotri

यामना। श्रृणुतं। हवं। मे। उत। त्या। वां। रुशतः। वप्ससः। गीः। त्रिऽवर्हिषि। सदसि। पिन्वते। नॄन्।

वृषा। वां। मेघः। वृषणा। पीपाय। गोः। न। सेके। मनुषः। दशस्यन्। युवां। पूषाऽइव। अश्विना। पुरंऽ

धिः। अग्निं। उषां। न। जरते। हविष्मान्। हुवे। यत्। वां। वरिवस्या। गृणानः। ९। २६। अभूत्। इदं। व

युनं। ओ इति। सु। भूषत। रथः। वृषण्ऽवान्। मदत। मनीषिणः। धियंऽजिन्वा। धिष्ण्या। विश्पला।

वसू इति। दिवः। नपाता। सुऽकृते। शुचिऽव्रता। इंद्रतमा। हि। धिष्ण्या। मरुत्ऽतमा। दस्रा। दंसिष्ठा।

रथ्या। रथिऽतमा। पूर्णं। रथं। वहेथे इति। मध्वः। आऽचितं। तेन। दाश्वांसं। उप। याथः। अश्विना। किं।

अत्र। दस्रा। कृणुथः। किं। आसाथे इति। जनः। यः। कः। चित्। अहविः। महीयते। अति। क्रमिष्टं।

© Dharmartha Trust J&K. Digitized by eGangotri

५दि जुरतं।पत्वेः।अस्तं।ज्योतिः।विश्पलायै।कृणुतं।वचस्यवे॥ऽजं।मयतं।अभितः।रायतः।शुनः।हतं।मृधः।
६१ विदथुः।तानि।अश्विना।वा।चं।वा।चं।जरितुः।रत्नीऽकृतं।तु।भा।शंसं।ना।सत्या।अवतं।मम।मा।यु नी
वां।एतं।चक्रथुः।सिंधुषु।प्लवं।आत्मन्ऽवंतं।पक्षिणं।तौग्र्याय।कं।येन।देवऽत्रा।मनसा।निःऽ
ह ऊहथुः।सुऽपप्तनी।पेतथुः।क्षोदसः।महः॥२७॥अवऽविद्धं।तौग्र्यं।अपऽसु।अंतः।अनारंभणे।
तमसि।प्रऽविद्धं।चतस्रः।नावः।जठलस्य।जुष्टाः।उत्।अश्विभ्यां।इषिताः।पारयंति।कः।स्वित्
वृक्षः।निःऽस्थितः।मध्ये।अर्णसः।यं।तौग्र्यः। नाधितः।परिऽअसस्वजत्।पर्णाः।मृगस्य। ज
पतरोःऽइव।आऽरभे।उत्।अश्विनौ।ऊहथुः।श्रोमताय।कं।तत्।वां।नरा।नासत्यौ।अनु।स्यात् ६२

© Dharmartha Trust J&K. Digitized by eGangotri

त्‌।यत्‌।वां।मानासः।उचथैः।आ।अवोचन्‌।अस्मात्‌।अद्य।सदसः।सोम्यात्‌।आ।८॥ २८ ॥ तं।युंजाथां।म
५ नसः।यः।जवीयान्‌।त्रिऽवंधुरः।वृषणा।यः।त्रिऽचक्रः।येन।उपऽयाथः।सुऽकृतः।दुरोणं।त्रिऽधा
तुना।पतथः।विः।न।पर्णैः।सुऽवृत्‌।रथः।वर्तते।यन्‌।अभि।क्षां।यत्‌।तिष्ठथः।क्रतुऽमंता।अनु
पृक्षे।वपुः।वपुष्या।सचतां।इयं।गीः।दिवः।दुहित्रा।उषसा।सचेथे इति।आ।तिष्ठतं।सुऽवृतं।
यः।रथः।वां।अनु।व्रतानि।वर्तते।हविष्मान्‌।येन।नरा।नासत्या।इषयध्यै।वर्तिः।याथः।त
नयाय।त्मने।च।मा।वां।वृकः।मा।वृकीः।आ।दधर्षीत्‌।मा।परि।वर्क्तं।उत।मा।अति।धक्तं।
अयं।वां।भागः।निऽहितः।इयं।गीः।दस्रौ।इमे।वां।निऽधयः।मधूनां।युवां।गोतमः।पुरुऽमीळ्हः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ अत्रिः।दस्रा।हवंते।अवसे।हविष्मान्।दिशां।ना।दिष्टां।ऋजुया।इव।यंता।आ।मे।हवं।नासत्या।

६२ उप।याते।०प्रति।वां।स्तोमः।अश्विना।अधायि।आ।इह।याते।पथिऽभिः।देवऽयानैः।०।२९।

इतिद्वितीयाष्टकेचतुर्थोध्यायः॥ ॥ॐ॥नावोकेतैरेकादशद्यावापृथिवीयमानोवैश्वदेवं

62 पितुन्वंन्नस्तुतिगोयत्रंत्वाद्यानुष्टुप् गर्भोत्तृतीयात्स्वपंचम्याद्याश्चतिस्रोनुष्टुभोत्याश्चबृह

तीर्यासमिद्धआप्रियोग्नेनयाष्टावाग्नेयमन्वर्णंबार्हस्पत्यसंकेकृतःषोडशोपानिषद्पूर्ण

सौर्यमानुष्टुभंविघ्रशंकावानगस्त्यःप्राग्वीदशम्याद्याश्चतिस्रोमहापंक्तयोमहाबृहतीवैय

ओगिरस्तःशौनहोत्रोभूत्वाभार्गवःशौनकोभवत्सगृत्समदोद्वितीयंमंडलमपश्यत्त्वमग्नेऽगा ६२

© Dharmartha Trust J&K. Digitized by eGangotri

गतंतुयज्ञेनसस्तोनासमिद्ध९कादशग्रंसप्तमीजगतीकुवेनवसोमाकुतिर्भागवोह्होनाष्टावा
नुष्टुभमिमांमेगायत्रंहि।अग्नेवषट्वाजयंनिवांस्यानुष्टुप्॥ ॥हरिःॐ॥ता।वां।अद्य।तौ।अप
रं।हुवेम।उच्छन्त्यां।उषसि।वन्हिः।उक्थैः।नासत्या।कुह।चित्।सन्तौ।अर्यः।दिवः।नपाता।सुदाःऽ
तराय।अस्मे इति।ऊं इति।सु।वृषणा।मादयेथां।उत्।पणीन्।हतं।ऊर्म्या।मदन्ता।श्रुतं।मे।अच्छो
क्तिऽभिः।मतीनां।आऽइष्टा।नरा।निऽचेतारा।च।कर्णैः।श्रिये।पूषन्।इषुकृताऽइव।देवा।नासत्या
वहतुं।सूर्यायाः।वच्यन्ते।वां।ककुहाः।अप्ऽसु।जाताः।युगा।जूर्णाऽइव।वरुणस्य।भूरेः।
अस्मे इति।सा।वां।माध्वी इति।रातिः।अस्तु।स्तोमं।हिनोतं।मान्यस्य।कारोः।अनु।यत्।वां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ छिं श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदंति । एषः । वां । स्तोमः । अश्विनौ । अकारि ।
६३ मानेभिः । मघऽवाना । सुऽवृक्ति । यातं । वर्तिः । तनयाय । त्मने । च । अगस्त्ये । नासत्या । मदंता ।०।१।
कतरा । पूर्वा । कतरा । अपरा । अयोः । कथा । जाते इति । कवयः । कः । वि । वेद । विश्वं । त्मना । बिभृतः ।
63 यत् । ह । नाम । वि । वर्तेते इति । अहनी इति । चक्रियाऽइव । भूरिं । द्वे इति । अचरंती इति । चरंतं । प
त्ऽवंतं । गर्भं । अपदी इति । दधाते इति । नित्यं । न । सूनुं । पित्रोः । उपऽस्थे । द्यावा । रक्षतं । पृथिवी इ
ति । नः । अभ्वात् । अनेहः । दात्रं । अदितेः । अनर्वं । हुवे । स्वःऽवत् । अवधं । नमस्वत् । तत् । रोदसी इ
ति । जनयतं । जरित्रे ।०। अतप्यमाने इति । अवसा । अवंती इति । अनु । स्याम । रोदसी इति । देवपु ६३

© Dharmartha Trust J&K. Digitized by eGangotri

त्रे इति देवऽपुत्रे। उभे इति। देवानां। उभयेभिः। अन्हां। ०। संगछमाने इति सं्ऽगछमाने। युवती इति। समन्ते
इति सं्ऽअंते। स्वसारा। जामी इति। पित्रोः। उपऽस्थे। अभिजिघ्रंती इत्यभिऽजिघ्रंती। भुवनस्य। नाभिं।
गा। रा। उर्वी इति। सद्मनी इति। बृहती इति। ऋतेन। हुवे। देवानां। अवसा। जनित्री इति। दधाने इति। ये
इति। अमृतं। सुप्रतीके इति सुऽप्रतीके। ०। उर्वी इति। पृथ्वी इति। बहुले इति। दूरेअंते इति दूरेऽअंते। उप।
ब्रुवे। नमसा। यज्ञे। अस्मिन्। दधाने इति। ये इति। सुभगे इति सुऽभगे। सुप्रतूर्ती इति सुऽप्रतूर्ती। ०।
देवान्। वा। यत्। चकृम। कत्। चित्। आगः। सखायं। वा। सदं। इत्। जाःऽपतिं। वा। इयं। धीः। भूयाः। अ
वऽयानां। एषां। ०। उभा। शंसा। नर्या। मां। अविष्टां। उभे इति। मां। ऊती इति। अवसा। सचेतां। भूरि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.द्वि: चित्रा। अर्यः। सुऽदाः। नेरा। यया। इषा। मर्दन्तः। इषयेम। देवाः। ऋतं। दिवे। नमः। अवो। चां। पृथिव्यै। अभिः। आ
६८ नाथ। प्रथमं। सुऽमेधाः। पातां। अवद्यात्। दुःऽइतात्। अभीकें। पिता। माता। चा। रक्षतां। अवःऽभिः
इदं। द्यावापृथिवी इति। सत्यं। अस्तु। पितः। मातः। यत्। इह। उपऽब्रुवे। वां। भूतं। देवानां। अवमे इ
ति। अवःऽभिः। ५। ३। आ। नः। इडाभिः। विदथे। सुऽशस्ति। विश्वानरः। सविता। देवः। एतु। अपि।
यथा। युवानः। मत्सथ। नः। विश्वं। जगत्। अभिऽपित्वे। मनीषा। आ। नः। विश्वे। आस्क्राः। गमंतु।
देवाः। मित्रः। अर्यमा। वरुणः। सऽजोषाः। भुवन्। यथा। नः। विश्वे। वृधासः। करन्। सुऽसहा। विथुरं। सा
न। शवः। प्रेष्ठं। वः। अतिथिं। गृणीषे। अग्निं। शस्तिऽभिः। तुर्वणिऽभिः। सऽजोषाः। असत्। यथा। नः। ६८

64

© Dharmartha Trust J&K. Digitized by eGangotri

वरूणः । सुऽकीर्तिः । इषंः । च । पर्वताः । अरिऽगूर्तः । सूरिः । उप । वः । आ । ईषे । नमसा । जिगीषा । उषसान
क्ता । सुदुघाऽइव । धेनुः । समाने । अहन् । विऽमानः । अर्कं । विषुऽरूपे । पयसि । सस्मिन् । ऊधन् । उत ।
नः । अहिः । बुध्न्यः । मयः । करिति । शिशुं । न । पिप्युषीऽइव । वेति । सिंधुः । येन । नपातं । अपां । जु
नाम । मनःऽजुवः । वृषणः । यं । वहंति । ६ । उत । नः । ईं । त्वष्टा । आ । गंतु । अछ । स्मत् । सूरिऽभिः । अ
भिऽपित्वे । सऽजोषाः । आ । वृत्रऽहा । इंद्रः । चर्षणिऽप्राः । तुविःऽतमः । नरां । नः । इह । गम्याः । ॰ मतयः
अश्वऽयोगाः । शिशुं । न । गावः । तरुणं । रिहंति । तं । ईं । गिरः । जनयः । न । पत्नीः । सुरभिःऽतमं । नरां ।
नसंत । ॰ मरुतः । वृद्धऽसेनाः । स्मत् । रोदसी इति । सऽमनसः । सदंतु । पृषत्ऽअश्वासः । अवनयः ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा
१६ं नारथाः। रिदसः। मित्रऽयुजः। नादेवाः। प्रानुायत। एषां। महिना। चिकित्रे। प्र। युंजते। प्रऽयुजः। ते। सुः
६८ रक्ति। सुऽदिनेः। नाशरुः। विश्वं। आ। इरिणं। प्रुषायंत। सेनाः। प्रो इति। अश्विनौ। अवसे। कृ
णुध्वं। प्र। पूषणं। स्वऽतवसः। हि। संति। अद्वेषः। विष्णुः। वातः। ऋभुक्षाः। अच्छ। सुम्नाय। ववृतीय।
देवान्। इयं। सा। वः। अस्मे इति। दीधितिः। यजत्राः। अपिऽप्राणी। च। सदनी। च। भूयाः। नि। या।
देवेषु। यतते। वसुऽयुः। वाचा। पितुं। नु। स्तोषं। महः। धर्माणं। तविषीं। यस्य। त्रितः। वि। ओजसा।
वृत्रं। विऽपर्वं। अर्दयत्। स्वादो इति। पितो इति। मधो इति। पितो इति। वयं। त्वा। ववृमहे। अस्मा
कं। अविता। भव। उप। नः। पितो इति। आ। चर। शिवः। शिवाभिः। ऊतिऽभिः। मयः। ऽभुः। अद्वि ६९

© Dharmartha Trust J&K. Digitized by eGangotri

भ्यः।संऽखा।सुऽशेवः।अद्वयाः॥तव।त्ये।पितो इति।रसाः।रजांसि।अनु।विऽस्थिताः।दिवि।वाताः

ऽइव।श्रिताः॥७॥ददतः।तव।स्वादिष्ठ।ते।पितो इति।प्र।स्वाद्मानः।रसानां।तुविग्रीवाःऽइव।ईर

ते॥८॥त्वे इति।पितो इति।महानां।देवानां।मनः।हितं।अकारि।चारु।केतुना।तव।अहिं।अव

सा।अवधीत्।यत्।अदः।पितो इति।अजगन्।विवस्व।पर्वतानां।अत्र।चित्।नः।मधो इति।

पितो इति।अरं।भक्षाय।गम्याः॥यत्।अपां।ओषधीनां।परिंशं।आऽरिशामहे।वातापे।पीवः।इ

त्।भव।यत्।ते।सोम।गोऽआशिरः।यवऽआशिरः।भजामहे।०।करंभः।ओषधे।भव।पीवः।वृ

क्कः।उदारथिः।०।तं।त्वा।वयं।पितो इति।वचःऽभिः।गावः।हव्या।नः।सुसूदिम।देवेभ्यः।त्वा।सधऽमा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ दं। अस्मभ्यं। त्वा। सधऽमादं।।७।। संऽइद्धः। अद्य। राजसि। देवः। देवैः। सहस्वऽजित्। दूतः। हव्या। कविः। वहात। तनूऽ
६६ नपात्। ऋतं। यते। मध्वा। यज्ञः। सं। अज्यते। दधत्। सहस्रिणीः। इषः। आऽजुह्वानः। नः। ईड्यः। देवान्। आ। व
क्षि। यज्ञियान्। अग्ने। सहस्रऽसाः। असि। प्राचीनं। बर्हिः। ओजसा। सहस्रऽवीरं। अस्तृणन्। यत्र। आदि
त्याः। विऽराजथ। विऽराट्। संऽराट्। विऽभ्वीः। प्रऽभ्वीः। बह्वीः। च। भूयसीः। च। याः। दुरः। घृतानि। अक्षरन्।
।८।। सुरुक्मे इति सुऽरुक्मे। हि। सुऽपेशसा। अधि। श्रिया। विऽराजतः। उषसौ। आ। इह। सीदतां। प्रथमा।
हि। सुऽवस्वसा। भारती। इळा। सरस्वती। याः। वः। सर्वाः। उपऽब्रुवे। ताः। नः। चोदयत। श्रिये। त्वष्टा। रूपाणि।
हि। प्रऽभुः। पशून्। विश्वान्। संऽआनजे। तेषां। नः। स्फातिं। आ। यज। उप। त्मन्या। वनस्पते। पाथः। देवेभ्यः। ६६

© Dharmartha Trust J&K. Digitized by eGangotri

स्रजा। अग्निः। हव्यानि। सिस्वदत्। पुरःऽगाः। अग्निः। देवानां। गायत्रेण। सं। अज्यते। स्वाहाऽकृतीषु। रोचते।
॥९॥ अग्ने। नय। सुऽपथा। राये। अस्मान्। विश्वानि। देव। वयुनानि। विद्वान्। युयोधि। अस्मत्। जुहुराणं
।एनः। भूयिष्ठां। ते। नमःऽउक्तिं। विधेम। अग्ने। त्वं। पारय। नव्यः। अस्मान्। स्वस्तिऽभिः। अति। दुःऽगानि।
विश्वा। पूः। च। पृथ्वी। बहुला। नः। ऊर्वी। भव। तोकाय। तनयाय। शं। योः। अग्ने। त्वं। अस्मत्। युयोधि। अ
मीवाः। अनग्निऽत्राः। अभि। अमंत। कृष्टीः। पुनः। अस्मभ्यं। सुविताय। देव। क्षां। विश्वेभिः। अमृतेभिः। य
जत्र। पाहि। नः। अग्ने। पायुऽभिः। अजस्रैः। उत। प्रिये। सदने। आ। शुशुक्वान्। मा। ते। भयं। जरितारं। य
विष्ठ। नूनं। विदत्। मा। अपरं। सहस्वः। मा। नः। अग्ने। अव। सृजः। अघाय। अविष्यवे। रिपवे। दुच्छुनायै।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰छि॰ मा । दुःऽवते । दशते । मा । अदते । नः । मा । रिषते । सहसाऽवन् । परा । दाः ॥ ५ ॥ वि । घ । त्वाऽवान् । ऋतऽजात । यं
६७ सत् । गृणानः । अग्ने । तन्वे । वरूथं । विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुतां । असि । हि । दे
व । विष्पट् । त्वं । तान् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रऽपित्वे । मनुषः । यजत्र । अभिऽपित्वे । मनवे । शा
स्यः । भूः । मर्मृजेन्यः । उशिक्ऽभिः । न । अक्रः । अवोचाम । निऽवचनानि । अस्मिन् । मानस्य । सूनुः । स
हसाने । अग्नौ । वयं । सहस्रं । ऋषिऽभिः । सनेम ॥ ८ ॥ अनर्वाणं । वृषभं । मन्द्रऽजिह्वं । बृहस्पतिं । वर्द्ध
य । नव्यं । अर्कैः । गाथान्यः । सुऽरुचः । यस्य । देवाः । आऽशृण्वन्ति । नवमानस्य । मर्ताः । तं । ऋत्वियाः । उप । वा
चः । सचन्ते । सर्गः । न । यः । देवऽयतां । असर्जि । बृहस्पतिः । सः । हि । अंजः । वरांसि । विऽभ्वा । अभवत् । सं । ऋते ६७

© Dharmartha Trust J&K. Digitized by eGangotri

ता। मातरिश्वा। उपऽस्तुतिं। नमस्सः। उत्ऽयतिं। च। श्लोकं। यं। सता। सविता। ऽइव। प्रा। बाहू इति। अस्य। क्रत्वा।
अहन्यः। यः। अस्ति। मृगः। नाभीमः। अरक्षसः। तुविष्मान्। अस्य। श्लोकः। दिविऽईयते। पृथिव्यां।
अस्यः। ना। यं। सता। यक्षऽभृता। विऽचेताः। मृगाणां। ना। हेतयः। यंति। चा। इमाः। बृहस्पतेः। अहिऽमायान्।
अभि। द्यून्। यो। वा। देवा। उस्रिकं। मन्यमानाः। पापाः। भद्रं। उपऽजीवंति। पज्राः। ना। दुःऽध्ये। अनु। ददा
सि। वामं। बृहस्पते। चयसे। इत्। पियारुं॥ १२॥ सुऽप्रैतुः। सुऽयवसः। ना। पंथाः। दुःऽनियंतुः। परिऽप्री
तः। ना। मित्रः। अनर्वाणः। अभि। यो। चष्टे। नाः। अविऽरताः। अपऽऊर्णुवंतः। अस्तु। सः। यः। स्तुमः।
अवनयः। ना। यंति। समुद्रं। ना। स्रवतः। रोधऽचक्राः। सः। विद्वान्। उभयं। चष्टे। अंतः। बृहस्पतिः। तरः।

© Dharmartha Trust J&K. Digitized by eGangotri

१।हि। आपवः। वाग्ध्वः। एव। मह्ः। तुविऽजातः। तुविष्मान्। बृहस्पतिः। वृषभः। धायि। देवः। सः। नः। स्तुतः। वीरऽव

६८ त्। धातु। गोऽमत्।वा।३३।। कंकतः। न। कंकतः। अथो इति। सतीनऽकंकतः। द्वौ इति। प्लुषी इति। इति। नि।

अदृष्टाः। अलिप्सत। अदृष्टान्। हन्ति। आऽयती। अथो इति। हन्ति। पराऽयती। अथो इति। अवऽघ्नती। हन्

68 ति। अथो इति। पिनष्टि। पिंषती। शरासः। कुशरासः। दर्भासः। सैर्याः। उत। मौंजाः। अदृष्टाः। वैरिणाः। स

र्वे। साकं। नि। अलिप्सत। नि। गावः। गोऽस्थे। असदन्। नि। मृगासः। अविक्षत। नि। केतवः। जनानां।

नि। अदृष्टाः। अलिप्सत। एते। ऊं इति। त्ये। प्रति। अदृश्रन्। प्रऽदोषं। तस्कराःऽइव। अदृष्टाः। विश्वऽदृष्टाः।

प्रतिऽबुद्धाः। अभूतन। १४।। द्यौः। वः। पिता। पृथिवी। माता। सोमः। भ्राता। अदितिः। स्वसा। अदृष्टाः। ६८

© Dharmartha Trust J&K. Digitized by eGangotri

विश्वऽदृष्टाः । इति । षट्ना । इल्लवत्ता । सु । कं । ये । अंस्याः । ये । अंग्याः । सूचीकाः । ये । प्रऽकंकताः । अदृष्टाः । किं । चन ।
इह । वः । सर्वे । साकं । नि । जस्यत । उत् । पुरस्तात् । सूर्यः । एति । विश्वऽदृष्टः । अदृष्टऽहा । अदृष्टान् । सर्वान् । जं
भयन् । सर्वाः । च । यातुऽधान्यः । उत् । अपप्तत् । असौ । सूर्यः । पुरु । विश्वानि । जूर्वन् । आदित्यः । पर्वतेभ्यः ।
विश्वऽदृष्टः । अदृष्टऽहा । सूर्ये । विषं । आ । सजामि । दृतिं । सुराऽवतः । गृहे । सः । चित् । नु । न । मराति । नो इति ।
वयं । मराम । आरे । अस्य । योजनं । हरिऽस्थाः । मधुः । ला । मधुला । चकार ॥ १५ ॥ इयत्तिका । शकुंतिका । स
का । जघास । ते । विषं । सो इति । ॰ त्रिः । सप्त । विष्पुलिंगकाः । विषस्य । पुष्यं । अक्षन् । ताः । ॰ मरंति । ॰ न
वानां । नवतीनां । विषस्य । रोपुषीणां । सर्वासां । अग्रभं । नामा । ॰ त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ अनुवः।नाः।ते।विषं।चिजभ्रिरे।उदकं।कुंभिनीःऽइव।इयत्तकः।कुषुंभकः।तकं।भिनद्मि।अश्मना।त

६९ तः।विषं।प्र।ववृते।पराचीः।अनु।संऽवतः।कुषुंभकः।तत्।अब्रवीत्।गिरेः।प्रऽवर्त्तमानकः।वृश्चिकस्य।

69 अरसं।विषं।अरसं।वृश्चिक।ते।विषं।१६।इति द्वितीयं मंडलं।त्वं।अग्ने।द्युऽभिः।त्वं।आशुशुक्षणिः।

त्वं।अत्ऽभ्यः।त्वं।अश्मनः।परि।त्वं।वनेभ्यः।त्वं।ओषधीभ्यः।त्वं।नृणां।नृऽपते।जायसे।शुचिः।तव।अ

ग्ने।होत्रं।तव।पोत्रं।ऋत्वियं।तव।नेष्ट्रं।त्वं।अग्नित्।ऋतऽयतः।तव।प्रऽशास्त्रं।त्वं।अध्वरिऽयसि।ब्रह्मा।

च।असि।गृहऽपतिः।च।नः।दमे।त्वं।अग्ने।इंद्रः।वृषभः।सतां।असि।त्वं।विष्णुः।उरुऽगायः।नमस्यः।

त्वं।ब्रह्मा।रयिऽवित्।ब्रह्मणः।पते।त्वं।विधर्त्तः।सिचसे।पुरंऽध्या।त्वं।अग्ने।राजा।वरु ६९

© Dharmartha Trust J&K. Digitized by eGangotri

णः। धृतऽव्रतः। त्वं। मित्रः। भवसि। दस्मः। ईड्यः। त्वं। अर्यमा। सत्ऽपतिः। यस्य। संऽभुजं। त्वं। अंशः। वि
दथे। देव। भाजयुः। त्वं। अग्ने। त्वष्टा। विधते। सुऽवीर्यं। तव। ग्नावः। मित्रऽमहः। सऽजात्यं। त्वं। आशुऽहे
मा। ररिषे। सुऽअश्व्यं। त्वं। नरां। शर्द्धः। असि। पुरुऽवसुः॥५॥ त्वं। अग्ने। रुद्रः। असुरः। महः। दिवः।
त्वं। शर्द्धः। मारुतं। पृक्षः। ईशिषे। त्वं। वातैः। अरुणैः। यासि। शंऽगयः। त्वं। पूषा। विधतः। पासि। नु। त्म
ना। त्वं। अग्ने। द्रविणःऽदाः। अरंऽकृते। त्वं। देवः। सविता। रत्नऽधाः। असि। त्वं। भगः। नृऽपते। वस्वः। ई
शिषे। त्वं। पायुः। दमे। यः। ते। अविधत्। त्वां। अग्ने। दमे। आ। विश्पतिं। विशः। त्वां। राजानं। सुऽविदत्रं।
ऋंजते। त्वं। विश्वानि। सुऽअनीक। पत्यसे। त्वं। सहस्राणि। शता। दश। प्रति। त्वां। अग्ने। पितरं। इ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ ष्टिऽभिः। नरः। त्वां। भ्रात्राय। शम्या। तनूऽरुचं। त्वं। पुत्रः। भवसि। यः। ते। अविधत्। त्वं। सखा। सुऽशेवः

७० । पासि। आऽधृषः। त्वं। अग्ने। ऋभुः। आके। नमस्यः। त्वं। वाजस्य। क्षुऽमतः। रायः। ईशिषे। त्वं। वि। भा

सि। अनु। धक्षि। दावने। त्वं। विऽशिक्षुः। असि। यज्ञं। आऽतनिः। ॥९॥ त्वं। अग्ने। अदितिः। देव। दाशु

70 षे। त्वं। होत्रा। भारती। वर्द्धसे। गिरा। त्वं। इळा। शतऽहिमा। असि। दक्षसे। त्वं। वृत्रऽहा। वसुऽपते। स

रस्वती। त्वं। अग्ने। सुऽभृतः। उत्ऽतमं। वयः। तव। स्पार्हे। वर्णे। आ। संऽदृशि। श्रियः। त्वं। वाजः। प्रऽ

तरणः। बृहन्। असि। त्वं। रयिः। बहुलः। विश्वतः। पृथुः। त्वां। अग्ने। आदित्यासः। आस्यं। त्वां। जि

ह्वां। शुचयः। चक्रिरे। कवे। त्वां। रातिऽसाचः। अध्वरेषु। सश्चिरे। त्वे इति। देवाः। हविः। अदंति। आऽहुतं। ७०

अत्री।

त्वेइति। अग्ने। विश्वे। अमृतासः। अद्रुहः। आसा। देवाः। हविः। अदंति। आऽहुतं। त्वया। मर्तीसः। स्वदंते। आ

ऽयुतिं। त्वं। गर्भः। वीरुधां। जज्ञिषे। शुचिः। त्वं। तान्। सं। च। प्रति। च। असि। मज्मना। अग्ने। सुऽजातः। प्र। च।

देवा। रिच्यसे। पृक्षः। यत्। महिना। वि। ते। भुवत्। अनु। द्यावापृथिवीइति। रोदसीइति। उभेइति। ये। स्तो

तऽभ्यः। गोऽअग्रां। अश्वऽपेशसं। अग्ने। रातिं। उपऽसृजंति। सूरयः। अस्मान्। च। तान्। च। प्र। हि। नेषि। व

स्यः। आ। बृहत्। वदेम। विदथे। सुऽवीराः। इत्रा। यज्ञेन। वर्द्धत। जातऽवेदसं। अग्निं। यजध्वं। हविषा। तन

ना। गिरा। संऽइधानं। सुऽप्रयसं। स्वःऽनरं। द्युक्षं। होतारं। [illegible]षु। वृजनेषु। धूःऽसदं। अभि। त्वा। नक्तीः।

उषसः। ववाशिरे। अग्ने। वत्सं। न। स्वसरेषु। धेनवः। दिवःऽइव। इत्। अरतिः। मानुषा। युगा। आ। क्षपः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ भासा।पुरुऽवारा।संऽयतः।तं।देवाः।बुध्ने।रजसः।सुऽदंससं।दिवः।पृथिव्योः।अरतिं।नि।एरिरे।रथंऽइ
८१ व।वेद्यं।शुक्रऽशोचिषं।अग्निं।मित्रं।न।क्षितिषु।प्रऽशंस्यं।तं।उक्षमाणं।रजसि।स्वे।आ।दमे।चंद्रंऽ
इव।सुऽरुचं।ह्वारे।आ।दधुः।पृश्न्याः।पतरं।चितयंतं।अक्षऽभिः।पाथः।न।पायुं।जनसीइति।उभेइति।
71 अनु।सः।होता।विश्वं।परि।भूतु।अध्वरं।तं।ऊंइति।हव्यैः।मनुषः।ऋंजते।गिरा।हिरिऽशिप्रः।वृध
सानासु।जर्भुरत्।द्यौः।न।स्तृऽभिः।चितयत्।रोदसीइति।अनु॥२०॥सः।नः।रेवत्।संऽइधानः।
स्वस्तये।संऽददस्वान्।रयिं।अस्मासु।दीदिहि।आ।नः।कृणुष्व।सुविताय।रोदसीइति।अग्ने।ह
व्या।मनुषः।देव।वीतये।दाः।नः।अग्ने।बृहतः।दाः।सहस्रिणः।दुरः।न।वाजं।श्रुत्यै।अप।वृधि। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

प्राचीइति। द्यावापृथिवीइति। ब्रह्मणा। कृधि। स्वः। न। शुक्रं। उषसः। वि। दिद्युतुः। सः। इधानः। उ
षसः। राम्याः। अनु। स्वः। न। दीदेत्। अरुषेण। भानुना। होत्राभिः। अग्निः। मनुषः। सुऽअध्वरः।
राजा। विशां। अतिथिः। चारुः। आयवे। एव। नः। अग्ने। अमृतेषु। पूर्व्य। धीः। पीपाय। बृहत्ऽदिवेषु
। मानुषा। दुहाना। धेनुः। वृजनेषु। कारवे। त्मना। शतिनं। पुरुऽरूपं। इषणि। वयं। अग्ने। अर्वता।
वा। सुऽवीर्यं। ब्रह्मणा। वा। चितयेम। जनान्। अति। अस्माकं। द्युम्नं। अधि। पंच। कृष्टिषु। उच्चा।
स्वः। न। शुशुचीत। दुस्तरं। सः। नः। बोधि। सहस्य। प्रऽशंस्यः। यस्मिन्। सुऽजाताः। इषयंत। सू
रयः। यं। अग्ने। यज्ञं। उपऽयंति। वाजिनः। नित्ये। तोके। दीदिऽवांसं। स्वे। दमे। उभयासः। जातऽवे

© Dharmartha Trust J&K. Digitized by eGangotri

प॰छि॰ दः॥स्याम।ते।स्तोतारः।अग्ने।सूरयेः।च।शर्मणि।वस्वः।रायः।पुरुऽचंद्रस्य।भूयसः।प्रजाऽवतः।सुऽ
७२ अपत्यस्य।शग्धि।नः।॥२३॥ संऽइद्धः।अग्निः।निऽहितः।पृथिव्यां।प्रत्यङ्।विश्वानि।भुवनानि।अ
स्थात्।होता।पावकः।प्रऽदिवः।सुऽमेधाः।देवः।देवान्।यजतु।अग्निः।अर्हन्।नराशंसः।प्रति।धा
72 मानि।अंजन्।तिस्रः।दिवः।प्रति।मह्ना।सुऽअर्चिः।घृतऽप्रुषा।मनसा।हव्यं।उंदन्।मूर्द्धन्।यज्ञ
स्य।सं।अनक्तु।देवान्।ईळितः।अग्ने।मनसा।नः।अर्हन्।देवान्।यक्षि।मानुषात्।पूर्वः।अद्य।सः।
आ।वह।मरुतां।शर्द्धः।अच्युतं।इंद्रं।नरः।बर्हिऽसदं।यजध्वं।देवाः।बर्हिः।वर्द्धमानं।सुऽवीरं।स्तीर्णं।
राये।सुऽभरं।वेदी।इति।अस्यां।घृतेन।अक्तं।वसवः।सीदत।इदं।विश्वे।देवाः।आदित्याः।यज्ञिया ७२

© Dharmartha Trust J&K. Digitized by eGangotri

सः। वि। प्रथंतां। उर्विया। हूयमानाः। द्वारः। देवीः। सुप्रऽअयनाः। नमःऽभिः। व्यचस्वतीः। वि। प्रथंतां।
अजुर्याः। वर्णं। पुनानाः। यशसं। सुऽवीरं॥ २२॥ साधु। अपांसि। सनता। नः। उक्षितेइति। उषासानक्ता।
वय्याऽइव। रण्वितेइति। तंतुं। ततं। संवयंतीइति संऽवयंती। समीचीइति समऽईची। यज्ञस्य। पेशः। सुदु
घेइति सुऽदुघे। पयस्वतीइति। दैव्या। होतारा। प्रथमा। विदुःऽतरा। ऋजु। यक्षतः। सं। ऋचा। वपुःऽ
तरा। देवान्। यजंतौ। ऋतुऽथा। सं। अंजतः। नाभा। पृथिव्याः। अधि। सानुषु। त्रिषु। सरस्वती। साध
यंती। धियं। नः। इळा। देवी। भारती। विश्वऽतूर्तिः। तिस्रः। देवीः। स्वधया। बर्हिः। आ। इदं। अछिद्रं।
पांतु। शरणं। निऽसद्य। पिशंगऽरूपः। सुऽभरः। वयःऽधाः। श्रुष्टी। वीरः। जायते। देवऽकामः। प्रऽ

© Dharmartha Trust J&K. Digitized by eGangotri

हविः। नर

पृ॰हिं जां।त्वष्टा।वि।स्यतु।नाभिं।अस्मै इति।अथ।देवानां।अपि।एतु।पाथः।वनस्पतिः।अवऽसृजन्।

७३ उप।स्थात्।अग्निः।स्वदयाति।प्राधीभिः।त्रिधा।संऽअक्तं।नयतु।प्रऽजानन्।देवेभ्यः।दैव्यः।शमिता।

उप।हव्यं।घृतं।मिमिक्षे।घृतं।अस्य।योनिः।घृते।श्रितः।घृतं।ऊं इति।अस्य।धाम।अनुऽस्वधं।आ।

73

वह।मादयस्व।स्वाहाऽकृतं।वृषभ।वक्षि।हव्यं।१३।कुवा।वः।सुघोमानं।सुऽवृक्तिं।विशां।अग्निं।

अतिथिं।सुऽप्रयसं।मित्रःऽइव।यः।दिधिषाय्यः।भूत्।देवः।आऽदेवा।जने।जातऽवेदः।इमं।विधंनः

।अपां।सधऽस्थे।हिता।अदधुः।भृगवः।विक्षु।आयोः।एषः।विश्वानि।अभि।अस्तु।भूम।देवानां।

।अग्निः।अरतिः।जीरऽअश्वः।अग्निं।देवासः।मानुषीषु।विक्षु।प्रियं।धुः।क्षेष्यंतः।न।मित्रं।सः। ७३

© Dharmartha Trust J&K. Digitized by eGangotri

दीदयत्।उशतीः।ऊर्म्याः।आ।दक्षाय्यः।यः।दास्वते।दमे।आ।अस्य।रण्वा।स्वस्यऽइव।पुष्टिः।संऽदृष्टिः।
अस्य।हियानस्य।धक्षोः।विः।यः।भरिभ्रत्।ओषधीषु।जिह्वां।अत्यः।न।रथ्यः।दोधवीति।वारान्।आ
यत्।मे।अभ्वं।वनदः।पनंत।उशिक्ऽभ्यः।न।अमिमीत।वर्णं।सः।चित्रेण।चिकिते।रंसु।भासा।जुजु
र्वान्।यः।मुहुः।आ।युवा।भूत्।।रना।आ।यः।वना।ततृषाणः।न।भाति।वाः।न।पथा।रथ्याऽइव।स्वानी
त्।कृष्णऽअध्वा।तपुः।रण्वः।चिकेत।द्यौःऽइव।स्मयमानः।नभःऽभिः।सः।यः।वि।अस्थात्।अभि।धक्षत्।
उर्वीं।पशुः।न।एति।स्वऽयुः।अगोपाः।अग्निः।शोचिष्मान्।अतसानि।उष्णन्।कृष्णऽव्यथिः।अस्वद
यत्।न।भूम।नु।ते।पूर्वस्य।अवसः।अधिऽइतौ।तृतीये।विदथे।मन्म।शंसि।अस्मेइति।अग्ने।संऽयत्

© Dharmartha Trust J&K. Digitized by eGangotri

प॰दि॰ ७४ 74

वीरं।बृहंतं।क्षुऽमंतं।वाजं।सुऽअपत्यं।रयिं।दाः॥त्वया।यथा।गृत्सऽमदासः।अग्ने।गुहा।वन्वंतः।उ

परान्।अभि।स्युरिति।स्युः।सुऽवीरासः।अभिमातिऽसहः।स्मत्।सूरिऽभ्यः।गृणते।तत्।वयः।

धाः॥२५॥होता।अजनिष्ट।चेतनः।पिता।पितृऽभ्यः।ऊतये।प्रऽयक्षन्।जेन्यं।वसु।शकेम।वाजिनः।

यमं।आ।यस्मिन्।सप्त।रश्मयः।तताः।यज्ञस्य।नेतरि।मनुष्वत्।दैव्यं।अष्टमं।पोता।विश्वं।तत्।

इन्वति।दधन्वे।वा।यत्।ईं।अनु।वोचत्।ब्रह्माणि।वेः।ऊं इति।तत्।परि।विश्वानि।काव्या।नेमिः।

चक्रंऽइव।अभवत्।साकं।हि।शुचिना।शुचिः।प्रऽशास्ता।क्रतुना।अजनि।विद्वान्।अस्य।व्रता।

ध्रुवा।वयाःऽइव।अनु।रोहते।ताः।अस्य।वर्णं।आयुवः।नेष्टुः।सचंत।धेनवः।कुवित्।तिसृऽभ्यः। ७४

© Dharmartha Trust J&K. Digitized by eGangotri

आ। वरं। स्वसरः। याः। इदं। वपुः। यदि। मानुः। उप। स्वसा। घृतं। भरंती। अस्थित। तासां। अध्वर्युः। आऽ
गंता। यवः। वृष्टीऽइव। मोदते। स्वः। स्वाया। धायसे। कृणुतां। ऋत्विक्। ऋत्विजं। स्तोमं। यज्ञं। च। आ। नः।
अरं। वने। मा। ररिम। वयं। यथा। विद्वान्। अरं। करत्। विश्वेभ्यः। यजतेभ्यः। अयं। अग्ने। त्वेइति। अ
पि। यं। यज्ञं। चकृम। वयं॥ २६॥ इमां। मे। अग्ने। संऽइधं। इमां। उपऽसदं। वनेरिति वनेः। ०। अया। ते। अ
ग्ने। विधेम। ऊर्जः। नपात्। अश्वंऽइष्टे। एना। सुऽउक्तेन। सुऽजात। तं। त्वा। गीःऽभिः। गिर्वणसं। द्रवि
णस्युं। द्रविणःऽदः। सपर्येम। सपर्यवः। सः। बोधि। सूरिः। मघऽवा। वसुऽपते। वसुऽदावन्। युयो
धि। अस्मत्। द्वेषांसि। सः। नः। वृष्टिं। दिवः। परि। सः। नः। वाजं। अनर्वाणं। सः। नः। सहस्रिणीः। इषः।

© Dharmartha Trust J&K. Digitized by eGangotri

१·६· ईळानाय। अवस्यवे। यविष्ठ। दूत। नः। गिरा। यजिष्ठ। होतः। आ। गहि। अंतः। हि। अग्ने। ईयसे। विद्वान्।
७५ जन्म। उभया। कवे। दूतः। जन्याःऽइव। मित्र्यः। सः। विद्वान्। आ। च। पिप्रयः। यक्षि। चिकित्वः। आनुष
क्। आ। च। अस्मिन्। सत्सि। बर्हिषि॥ २७॥ श्रेष्ठं। यविष्ठ। भारत। अग्ने। द्युऽमंतं। आ। भर। वसो
इति। पुरुऽस्पृहं। रयिं। मा। नः। अरातिः। ईशत। देवस्य। मर्त्यस्य। च। पर्षि। तस्य। उत। द्विषः। वि
श्वाः। उत। त्वया। वयं। धाराः। उदन्याःऽइव। अति। गाहेमहि। द्विषः। शुचिः। पावक। वंद्यः। अग्ने। बृ
हत्। वि। रोचसे। त्वं। घृतेभिः। आऽहुतः। त्वं। नः। असि। भारत। अग्ने। वशाभिः। उक्षऽभिः। अष्टाऽ
पदीभिः। आऽहुतः। द्रुऽअन्नः। सर्पिःऽआसुतिः। प्रत्नः। होता। वरेण्यः। सहसः। पुत्रः। अद्भुतः। ७५

75

© Dharmartha Trust J&K. Digitized by eGangotri

।।२८।।वाजयन्ऽइव।नूर।रथान्।योगान्।अग्नेः।उप।स्तुहि।यशःऽतमस्य।मीळ्हुषः।यः।सुऽनी

थः।ददाशुषे।अजुर्यः।जरयन्।अरिं।चारुऽप्रतीकः।आऽहुतः।यः।उं इति।श्रिया।दमेषु।आ।दो

षा।उषसि।प्रऽशस्यते।यस्य।व्रतं।न।मीयते।आ।यः।स्वः।न।भानुना।चित्रः।विऽभाति।अ

र्चिषा।अंजानः।अजरैः।अभि।अत्रिं।अनु।स्वऽराज्यं।अग्निं।उक्थानि।ववृधुः।विश्वाः।अधि।

श्रियः।दधे।अग्नेः।इंद्रस्य।सोमस्य।देवानां।ऊतिऽभिः।वयं।अरिष्यंतः।सचेमहि।अभि।स्या

म।पृतन्यतः।।२९।।इतिद्वितीयाष्टके पंचमोध्यायः।। ।।ॐ।।निहोता जोहूत्रः श्रुधिसे केंद्रं

विराट्स्त्वान मर्तं स्यां योजातः पंचोनत्रं तुः सत्ता नां सा त्रिष्टुब ध्वर्य वो द्वादश प्रघदश प्रवो न

प॰द्वि॰ वांस्यात्रिष्टुप्तदस्यैमेद्धि। त्रिष्टुब्बंतं प्रातरपाथिवयंतेसनोविराड्रूपा। विश्वाजितेषड्त्रिष्टुब्बंतंत्रिकद्रुके

७८ षुचतुष्कमध्याद्यातिशाक्करमंस्याद्द्वि र्वागणानामेकोनाब्राह्मणस्यपत्यंहबाहेस्यस्यास्तुदशलिं

76 गा:पंचदश्यंस्येत्रिष्टुभौ॥ ॐ॥ नि। होता। होत॰ऽसदनो। विदानः। त्वेषः। दीदिवान्। असदत्। सुऽद

क्षः। अदब्धव्रतऽप्रमतिः। वसिष्ठः। सहस्रंऽभरः। शुचिऽजिह्वः। अग्निः। त्वां। दूतः। त्वं। ऊं इति। नः। प

रःऽपाः। त्वं। वस्यः। आ। वृषभ। प्रऽनेता। अग्ने। तोकस्य। नः। तने। तनूनां। अप्रऽयुछन्। दीद्यत्

बोधि। गोपाः। विधेम। ते। परमे। जन्मन्। अग्ने। विधेम। स्तोमैः। अवरे। सधऽस्थे। यस्मात्।

योनेः। उत्ऽआरिथ। यजे। तं। प्र। त्वे इति। हवींषि। जुहुरे। संऽइद्धे। अग्ने। यज। स्वाहुविषा। य ७८

© Dharmartha Trust J&K. Digitized by eGangotri

जीयान्‌। श्रुष्टी। दस्मं। अभि। गृणीहि। राधः। त्वं। हि। असि। रयिऽपतिः। रयीणां। त्वं। शुक्रस्य।
वचसः। मनोता। उभयं। ते। न। क्षीयते। वसव्यं। दिवेऽदिवे। जायमानस्य। दस्म। कृधि। क्षुऽमंतं
। जरितारं। अग्ने। कृधि। पतिं। सुऽअपत्यस्य। रायः। सः। एना। अनीकेन। सुऽविदत्रः। अस्मे
इति। यष्टा। देवान्‌। आऽयजिष्ठः। स्वस्ति। अदब्धः। गोपाः। उत। नः। परःऽपाः। अग्ने। द्युऽमत्
। उत। रेवत्। दिदीहि॥ ६॥ जोहूत्रः। अग्निः। प्रथमः। पिताऽइव। इळः। पदे। मनुषा। यत्। संऽइद्धः
। श्रियं। वसानः। अमृतः। विऽचेताः। मर्मृजेन्यः। श्रवस्यः। सः। वाजी। श्रुयाः। अग्निः। चि
त्रऽभानुः। हवं। मे। विश्वाभिः। गीःऽभिः। अमृतः। विऽचेताः। श्यावा। रथं। वहतः। रोहिता। वा। उ

© Dharmartha Trust J&K. Digitized by eGangotri

१·द्वि ता। अरुषा। अहा। चक्रे। विऽभृत्रः। उत्तानायां। अजनयन्। सुऽसूतं। भुवत्। अग्निः। पुरुऽपेशासु। गर्भः
७७ ।शिरिणायां। चित्। अक्तुना। महःऽभिः। अपरिऽवृतः। वसति। प्रऽचेताः। जिघर्मि। अग्निं। हविषा। घृ
तेन। प्रतिऽक्षियंतं। भुवनानि। विश्वा। पृथुं। तिरश्चा। वयसा। बृहंतं। व्यचिष्ठं। अन्नैः। रभसं। दृशानं।
आ। विश्वतः। प्रत्यंचं। जिघर्मि। अरक्षसा। मनसा। तत्। जुषेत। मर्यऽश्रीः। स्पृहयत्ऽवर्णः। अग्निः। न।
अभिऽमृशे। तन्वा। जर्भुराणः। ज्ञेयाः। भागं। सहसानः। वरेण। त्वाऽदूतासः। मनुष्वत्। वदेम। अनूनं।
अग्निं। जुह्वा। वचस्या। मधुऽपृचं। धनऽसाः। जोहवीमि। रा। श्रुधि। हवं। इंद्र। मा। रिषण्यः। स्याम। ते।
दावने। वसूनां। इमाः। हि। त्वां। ऊर्जः। वर्धयंति। वसुऽयवः। सिंधवः। न। क्षरंतः। स्रजः। मही। इंद्र। याः। ७७

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्र।

अपिन्वः।परिऽस्थिताः।अहिना।शूर।पूर्वीः।अमर्त्यं।चित्।दासं।मन्यमानं।अव।अभिनत्।उक्थैः।
।ववृधानः।उक्थेषु।इत्।नु।शूर।येषु।चाकन्।स्तोमेषु।रुद्रियेषु।च।तुभ्य।इत्।एताः।यासु।मंद
सानः।प्र।वायवे।सिस्रते।न।शुभ्राः।शुभ्रं।नु।ते।शुष्मं।वर्द्धयंतः।शुभ्रं।वज्रं।बाह्वोः।दधानाः।शु
भ्राः।त्वं।इंद्र।ववृधानः।अस्मे इति।दासीः।विशः।सूर्येण।सह्याः।गुहा।हितं।गुह्यं।गूळ्हं।अप्ऽ
सु।अपिऽवृतं।मायिनं।क्षियंतं।उतो इति।अपः।द्यां।तस्तभ्वांसं।अहन्।अहिं।शूर।वीर्येण॥ ५
॥स्तव।नु।ते।इंद्र।पूर्व्या।महानि।उत।स्तवाम।नूतना।कृतानि।स्तव।वज्रं।बाह्वोः।उशंतं।स्तव।
हरी इति।सूर्यस्य।केतू इति।हरी इति।नु।ते।इंद्र।वाजयंता।घृतऽश्चुतं।स्वारं।अस्वार्ष्टां।वि।

© Dharmartha Trust J&K. Digitized by eGangotri

१·द्वि· समनाभूमिः। अप्रथिष्ट। अरंस्त। पर्वतः। चित्। सरिष्यन्। नि। पर्वतः। सादि। अप्रऽयुच्छन्। सं। मातृऽ
७८ भिः। वावशानः। अक्रान्। दूरे। पारे। वाणीं। वर्द्धयंतः। इंद्रऽइषितां। धमनिं। पप्रथन्। नि। इंद्रः। महां।
सिंधुं। आऽशयानं। मायाऽविनं। वव्रं। अस्फुरत्। निः। अरेजेतां। रोदसी इति। भिया। ने इति। कनि
78 क्रदतः। वृष्णः। अस्य। वज्रात्। अरोरवीत्। वृषभः। अस्य। वज्रः। अमानुषं। यत्। मानुषः। निऽजू
र्वात्। नि। मायिनः। दानवस्य। मायाः। अपादयत्। पपिऽवान्। सुतस्य॥ ८॥ पिबऽपिब। इत्। इंद्र।
शूर। सोमं। मंदंतु। त्वा। मंदिनः। सुतासः। पृणंतः। ते। कुक्षी इति। वर्द्धयंतु। इत्था। सुतः। पौरः। इंद्रं। आ
अ वा। त्वे इति। इंद्र। अपि। भूम। विप्राः। धियं। वनेम। ऋतऽया। सपंतः। अवस्यवः। धीमहि। प्रऽशस्तिं। ७८

© Dharmartha Trust J&K. Digitized by eGangotri

सघः। ते। रायः। दावने। स्याम। स्याम। ते। ते। इंद्र। ये। ते। ऊती। अवस्यवः। ऊर्जं। वर्धयंतः। शुष्मिन्ऽतमं।
यं। चाकनाम। देवा। अस्मे इति। रयिं। रासि। वीरऽवंतं। रासि। क्षयं। रासि। मित्रं। अस्मे इति। रासि।
शर्धः। इंद्र। मा। रुतं। नः। सऽजोषसः। यो। च। मंदसानः। प्र। वायवः। पांति। अग्रऽनीतिं। व्यंतु। इत्। नु।
येषु। मंदसानः। तृपत्। सोमं। पाहि। द्रह्यत्। इंद्र। अस्मान्। सु। पृत्ऽसु। आ। तरुत्र। अवर्धयः। द्यां।
बृहत्ऽभिः। अर्कैः। ॥५॥ बृहंतः। इत्। नु। ये। ते। तरुत्र। उक्थेभिः। वा। सुम्नं। आऽविवासान्। स्तृणाना
सः। बर्हिः। पस्त्यऽवत्। त्वाऽऊताः। इत्। इंद्र। वाजं। अग्मन्। उग्रेषु। इत्। नु। शूर। मंदसानः। त्रिऽकद्रु
केषु। पाहि। सोमं। इंद्र। प्रऽदोधुवत्। श्मश्रुषु। प्रीणानः। याहि। हरिऽभ्यां। सुतस्य। पीतिं। पिब। शावः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ भूरा । येन । वृत्रं । अव । अभिनत् । दानुं । और्णऽवाभं । अप । अवृणोः । ज्योतिः । आर्याय । नि । सव्यतः । सा
७९ दि । दस्युः । इंद्र ॥ सनेम । ये । ते । ऊतिऽभिः । तरंतः । विश्वाः । स्पृधः । आर्येण । दस्यून् । अस्मभ्यं । तत् । त्वा
ष्ट्रं । विश्वऽरूपं । अरंधयः । साख्यस्य । त्रिताय ॥ अस्य । सुवानस्य । मंदिनः । त्रितस्य । नि । अर्बुदं । वा
79 वृधानः । अस्तरित्यस्तः । अवर्तयत् । सूर्यः । न । चक्रं । भिनत् । वलं । इंद्रः । अंगिरस्वान् ॥ नूनं । सा । ते । प्र
ति । वरं । जरित्रे । दुहीयत् । इंद्र । दक्षिणा । मघोनी । शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । ० । २१ ।
यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान् । क्रतुना । परिऽअभूषत् । यस्य । शुष्मात् । रोदसी इति ।
अभ्यसेतां । नृम्णस्य । मह्ना । सः । जनासः । इंद्रः ॥ यः । पृथिवीं । व्यथमानां । अदृंहत् । यः । पर्वतान् । ७९

© Dharmartha Trust J&K. Digitized by eGangotri

प्रऽकुपितान्। अरम्णात्। यः। अंतरिक्षं। विऽममे। वरीयः। यः। द्यां। अस्तभ्नात्। ०। यः। हत्वा। अहिं। अरि
णात्। सप्त। सिंधून्। यः। गाः। उत्ऽआजत्। अपऽधा। वलस्य। यः। अश्मनोः। अंतः। अग्निं। जजान।
संऽवृक्। समत्ऽसु। ०। येन। इमा। विश्वा। च्यवना। कृतानि। यः। दासं। वर्णं। अधरं। गुहा। अकरित्य
कः। श्वघ्नीऽइव। यः। जिगीवान्। लक्षं। आदत्। अर्यः। पुष्टानि। ०। यं। स्म। पृच्छंति। कुह। सः। इति। घो
रं। उत। ईं। आहुः। न। एषः। अस्ति। इति। एनं। सः। अर्यः। पुष्टीः। विजःऽइव। आ। मिनाति। श्रत्। अस्मै।
धत्त। ०। यः। रध्रस्य। चोदिता। यः। कृशस्य। यः। ब्रह्मणः। नाधमानस्य। कीरेः। युक्तऽग्राव्णः। यः।
अविता। सुऽशिप्रः। सुतऽसोमस्य। ०। यस्य। अश्वासः। प्रऽदिशि। यस्य। गावः। यस्य। ग्रामाः। य

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ स्य॑। विश्वे॑। रथा॑। सः। यः। सूर्यं॑। यः। उषसं॑। जजान॑। यः। अपां। नेता। ०। यं। क्रंद॑सी इति॑। संयती इति॑ सं॑ऽ
८० यती। विह्वये॑ते इति॑ विऽह्वये॑ते। परे॑। अवरे॑। उभयाः। अमित्राः। समानं। चित्। रथं॑। आतस्थिऽवांसा।
80 नाना। हवेते इति॑। ०। यस्मा॑त्। न। ऋते। विऽजय॑ते। जनाः। सः। यं। युध्य॑मानाः। अवसे। हवं॑ते। यः। विश्व॑
स्य। प्रतिऽमानं॑। बभूव॑। यः। अच्युतऽच्युत्। ०। यः। श॑श्वतः। महि। एनः। दधा॑नान्। अम॑न्यमानान्।
शर्वा॑। जघान॑। यः। शर्ध॑ते। न। अनुऽददा॑ति। शृध्यां। यः। दस्योः। हंता। ०। ०। यः। शंबरं॑। पर्व॑तेषु। क्षि
यंतं॑। चत्वारिंश्यां॑। शरदि॑। अनुऽअविं॑दत्। ओजायमा॑नं। यः। अहिं॑। जघान॑। दानुं॑। शया॑नं। ०। यः।
सप्तऽरश्मिः। वृषभः। तुविऽष्मान्। अवऽअसृ॑जत्। सर्त॑वे। सप्त। सिंधू॑न्। यः। रौहि॑णं। अस्फु॑रत्। व ८०

© Dharmartha Trust J&K. Digitized by eGangotri

ज्रऽबाहुः। द्यां। आऽरोहंतं। ७ द्यावा। चित्। अस्मै। पृथिवी इति। नमेते इति। शुष्मात्। चित्। अस्य। पर्व
ताः। भयंते। यः। सोमऽपाः। निऽचितः। वज्रऽबाहुः। यः। वज्रऽहस्तः। ८ यः। सुन्वंतं। अवति। यः। पचं
तं। यः। शंसंतं। यः। शशमानं। ऊती। यस्य। ब्रह्म। वर्धनं। यस्य। सोमः। यस्य। इदं। राधः। ९ यः। सु
न्वते। पचते। दुध्रः। आ। चित्। वाजं। दर्दर्षि। सः। किल। असि। सत्यः। वयं। ते। इंद्र। विश्वह। प्रियासः।
सुऽवीरासः। विदथं। आ। वदेम।। १।। ऋतुः। जनित्री। तस्याः। अपः। परि। मक्षु। जातः। आ। अविश
त्। यासु। वर्धते। तत्। आहनाः। अभवत्। पिप्युषी। पयः। अंशोः। पीयूषं। प्रथमं। तत्। उक्थ्यं। स
ध्रीं। ईं। आ। यंति। परि। बिभ्रतीः। पयः। विश्वऽप्स्न्याय। प्र। भरंत। भोजनं। समानः। अध्वा। प्रऽवतां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ अनु॑ऽस्व॒धां। यः। ता। अरु॑णोः। प्र॒थ॒मं। सः। अ॒स्मि॒। उ॒क्थ्यः। अनु॑। एकः॑। व॒द॒ति॑। यत्। दृदा॑ति। तत्। रू॒पा। मि॒

८१ नन्। तत्ऽअ॑पाः। एकः॑। ई॒य॒ते। वि॒श्वाः। एक॑स्य। वि॒ऽनु॒दः। ति॒ति॒क्ष॒ते॒। ० प्र॒ऽजाभ्यः॑। पु॒ष्टिं। वि॒ऽभजं॑तः। आ

स॒ते॒। र॒यिंऽइ॑व। पृ॒ष्ठं। प्र॒ऽभवं॑तं। आ॒ऽयते॑। असि॑न्वन्। दं॒ष्ट्रैः॑। पि॒तुः। अ॒त्ति॒। भोज॑नं। ०। अध॑। अ॒रु॒णोः। पृ॒

81

थि॒वीं। सं॒ऽदृशौ॑। दि॒वः। यः। धौ॒ती॒नां। अ॒हि॒ऽह॒न्। अरि॑णक्। प॒थः। तं। त्वा॒। स्तोमे॑भिः। उ॒दऽभिः॑। न। वा॒जि॒

नं॑। दे॒वं। दे॒वाः। अ॒ज॒न॒न्। ०॥ १०॥ यः। भोज॑नं। च॒। दय॑से। च॒। वर्ध॑नं। आ॒र्द्रात्। आ। शुष्कं॑। मधु॑ऽमत्। दु॒

दोहि॑थ। सः। शे॒व॒ऽधिं। नि। द॒धि॒षे॒। वि॒वस्व॑ति। विश्व॑स्य। एकः॑। ई॒शि॒षे॒। ०। यः। पु॒ष्पिणीः॑। च॒। प्र॒ऽस्वः॑।

च॒। ध॒र्मणा॑। अधि॑। दाने॑। वि। अ॒वनीः॑। अधा॑रयः। यः। च॒। अस॑माः। अज॑नः। दि॒द्युतः॑। दि॒वः। उ॒रुः। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

ऊर्वान् । अभितः । ० । यः । नार्मरं । सहऽवसुं । निःऽहंतवे । पृक्षाय्यं । च । दासऽवेशाय । च । अवहः । ऊर्ज
यंत्याः । अपरिऽविष्टं । आस्यं । उत । एव । अद्य । पुरुऽकृत । ० । शतं । वा । यस्य । दश । साकं । आ । अद्यः
एकस्य । श्रुष्टौ । यत् । ह । चोदं । आविथ । अरज्जौ । दस्यून् । सं । उनप् । दभीतये । सुप्रऽअव्यः । अभवः
। ० । विश्वा । इत् । अनु । रोधनाः । अस्य । पौंस्यं । ददुः । अस्मै । दधिरे । कृत्नवे । धनं । षट् । अस्तभ्नाः
विऽस्तिरः । पंच । संऽदृशः । परि । परः । अभवः । ० । १३ । सुऽप्रवाचनं । तव । वीर । वीर्यं । यत् । एकेन
क्रतुना । विंदसे । वसु । जातूऽस्थिरस्य । प्र । वयः । सहस्वतः । या । चकर्थ । सः । इंद्र । विश्वा । असि
उक्थ्यः । अरमयः । सरऽअपसः । तराय । कं । तुर्वीतये । च । वय्याय । च । स्रुतिं । नीचा । संतं । उत ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ अनयः।पराऽवृजं।प्र।अंधं।श्रोणम्।श्रवयन्।०।अस्मभ्यं।तत्।वसोइति।दानाय।राधः।सं।अर्थयस्व।
८२ बहु।ते।वसव्यं।इंद्र।यत्।चित्रं।श्रवस्याः।अनु।घून्।०।१३।।अध्वर्यवः।भरत।इंद्राय।सोमं।आ।अम
82 त्रेभिः।सिंचत।मद्यं।अंधः।कामी।हि।वीरः।सदं।अस्य।पीतिं।जुहोत।वृष्णे।तत्।इत्।एषः।वष्टि।अ
ध्वर्यवः।यः।अपः।वव्रिऽवांसं।वृत्रं।जघान।अशन्याऽइव।वृक्षं।तस्मै।एतं।भरत।तत्ऽवशाय।एषः
इंद्रः।अर्हति।पीतिं।अस्य।अध्वर्यवः।यः।दृभीकं।जघान।यः।गाः।उत्ऽआजत्।अप।हि।वलं।व
रिति।वः।तस्मै।एतं।अंतरिक्षे।न।वातं।इंद्रं।सोमैः।आ।ऊर्णुत।जूः।न।वस्त्रैः।अध्वर्यवः।यः।उरणं।
जघान।नव।चख्वांसं।नवतिं।च।बाहून्।यः।अर्बुदं।अव।नीचा।बबाधे।तं।इंद्रं।सोमस्य।भृथे।हि ८२

© Dharmartha Trust J&K. Digitized by eGangotri

नोत। अध्वर्यवः। यः। स्तु। अश्नं। जघान। यः। शुष्णं। अशुषं। यः। विऽअंसं। यः। पिप्रुं। नमुचिं। यः। रुधिऽ
क्रां। तस्मै। इंद्राय। अंधसः। जुहोत। अध्वर्यवः। यः। शतं। शंबरस्य। पुरः। बिभेद। अश्मनाऽइव। पूर्वीः।
यः। वर्चिनः। शतं। इंद्रः। सहस्रं। अपऽअवपत्। भरत। सोमं। अस्मै॥ १३॥ आ। सहस्रं। भूम्याः। उपऽस्थे।
अवपत्। जघन्वान्। कुत्सस्य। आयोः। अतिथिऽग्वस्य। वीरान्। नि। अवृणक्। भरत। सोमं। अस्मै।
अध्वर्यवः। यत्। नरः। कामयाध्वे। श्रुष्टी। वहन्तः। नशथ। तत्। इंद्रे। गभस्तिऽपूतं। भरत। श्रुताय।
इंद्राय। सोमं। यज्यवः। जुहोत। अध्वर्यवः। कर्तन। श्रुष्टी। अस्मै। वने। निऽपूतं। वने। उत्। नयध्वं। जु
षाणः। हस्त्यं। अभि। वावशे। वः। इंद्राय। सोमं। मदिरं। जुहोत। अध्वर्यवः। पयसा। ऊधः। यथा। गोः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.द्वि सोमेभिः।ईं।पृणता।भोजं।इंद्रं।वेद।अहं।अस्य।निऽभृतं।मे।एतत्।दित्संतं।भरथः।यजतः।चिकेत।अ
८३ ध्वर्यवः।यः।दिव्यस्य।वस्वः।यः।पार्थिवस्य।क्षम्यस्य।राजा।तं।ऊर्दरं।न।पृणत।यवेन।इंद्रं।सोमेभिः।
83 तत्।अपः।वः।अस्तु।॥३॥प्र।घ।नु।अस्य।महतः।महानि।सत्या।सत्यस्य।करणानि।वोचं।त्रिऽ
कद्रुकेषु।अपिबत्।सुतस्य।अस्य।मदे।अहिं।इंद्रः।जघान।अवंशे।द्यां।अस्तभायत्।बृहंतं।आ।
रोदसी इति।अपृणत्।अंतरिक्षं।०।सोमस्य।ता।मदे।इंद्रः।चकार।सद्मऽइव।प्राचः।वि।मिमाय।
मानैः।वज्रेण।खानि।अतृणत्।नदीनां।वृथा।असृजत्।पथिऽभिः।दीर्घऽयाथैः।०।सः।प्रऽवोळ्हॄ
न्।परिऽगत्य।दभीतेः।विश्वं।अधाक्।आयुधं।इद्धे।अग्नौ।सं।गोभिः।अश्वैः।असृजत्।रथेभिः।० ८३

© Dharmartha Trust J&K. Digitized by eGangotri

सः।ईं।महीं।धुनिं।एतोः।अरम्णात्।सः।अस्नातॄन्।अपारयत्।स्वस्ति।तान्।उत्ऽस्नाय।रयिं।अभि।
प्र।तस्थुः।०।।३५।।सः।उदंचं।सिंधुं।अरिणात्।महिऽत्वा।वज्रेण।अनः।उषसः।सं।पिपेष।अजवसः।
जविनीभिः।विऽरश्नन्।०।सः।विद्वान्।अपऽगोहं।कनीनां।आविः।भवन्।उत्।अतिष्ठत्।पराऽवृ
क्।प्रति।श्रोणः।स्थात्।वि।अनक्।अचष्ट।०।भिनत्।वलं।अंगिरःऽभिः।गृणानः।वि।पर्वतस्य।दृं
हितानि।ऐरत्।रिणक्।रोधांसि।कृत्रिमाणि।एषां।०।स्वप्नेन।अभिऽउप्य।चुमुरिं।धुनिं।च।
जघंथ।दस्युं।प्र।दभीतिं।आवः।रंभी।चित्।अत्र।विविदे।हिरण्यं।०।।३६।।प्र।वः।सतां।ज्येष्ठऽ
तमाय।सुऽस्तुतिं।अग्नौऽइव।संऽइधाने।हविः।भरे।इंद्रं।अजुर्यं।जरयंतं।उक्षितं।सनात्।यु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ वानं। अवसे। हुवामहे। यस्मात्। इंद्रात्। बृहतः। किं। चन। ईं। ऋते। विश्वानि। अस्मिन्। संऽभृता।
८४ अधि। वीर्या। जठरे। सोमं। तन्वि। सहः। महः। हस्ते। वज्रं। भरति। शीर्षणि। क्रतुं। न। क्षोणीभ्यां।
परिऽभ्वे। ते। इंद्रियं। न। समुद्रैः। पर्वतैः। इंद्र। ते। रथः। न। ते। वज्रं। अनु। अश्नोति। कः। चन। यत्। आ
शुऽभिः। पतसि। योजना। पुरु। विश्वे। हि। अस्मै। यजताय। धृष्णवे। क्रतुं। भरंति। वृषभाय। स
श्चते। वृषा। यजस्व। हविषा। विदुःऽतरः। पिब। इंद्र। सोमं। वृषभेण। भानुना। वृष्णः। कोशः। पव
ते। मध्वः। उर्मिः। वृषभऽअन्नाय। वृषभाय। पातवे। वृषणा। अध्वर्यू इति। वृषभासः। अद्रयः।
वृषणं। सोमं। वृषभाय। सुस्वति। ॥३॥ वृषा। ते। वज्रः। उत। ते। वृषा। रथः। वृषणा। हरी इति। ८४

© Dharmartha Trust J&K. Digitized by eGangotri

वृषभाणि। आ। युधा। रक्षसे। मदस्य। वृषभा। त्वं। ईशिषे। इंद्र। सोमस्य। वृषभस्य। तृष्णुहि। प्र। ते। नावं।
न। असमने। वचस्युवं। ब्रह्मणा। यामि। सवनेषु। दधृषिः। कुवित्। नः। अस्य। वचसः। निऽबोधिष
त्। इंद्रः। उत्सं। न। वसुनः। सिचामहे। उरा। संऽबाधा। तरा। अभि। आ। वृत्स्व। नः। धेनुः। न। वत्सं। य
वसस्य। पिप्युषी। सकृत्। सु। ते। सुमतिऽभिः। शतक्रतो इति शतऽक्रतो। सं। पत्नीभिः। न। वृषणः
। नसीमहि। व। २८। नूतना। अस्मै। नव्यं। अंगिरस्वत्। अर्चत। शुष्माः। यत्। अस्य। प्रत्नऽथा। उत्ऽ
ईरते। विश्वाः। यत्। गोत्रा। सहसा। परिऽवृता। मदे। सोमस्य। दृंहितानि। ऐरयत्। सः। मन्तुयः।
हा। प्रथमाय। धायसे। ओजः। मिमानः। महिमानं। आ। अतिरत्। शूरः। यः। युत्ऽसु। तन्वं। परिऽ

© Dharmartha Trust J&K. Digitized by eGangotri

१-हि: व्यत । शीर्षणि । द्यां । महिना । प्रति । अमुंचत । अध । अकृणोः । प्रथमं । वीर्यं । महत् । यत् । अस्य । अग्रे ।
८५ ब्रह्मणा । शुष्मं । ऐरयः । रथेऽस्थेन । हर्यऽश्वेन । विऽच्युताः । प्रऽजीरयः । सिस्रते । सध्र्यक् । पृथक् ।
85 अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानऽकृत् । प्रऽवयाः । अभि । अवर्धत । आत् । रोदसी
इति । ज्योतिषा । वन्हिः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सं । अव्ययत् । सः । प्राचीनान् ।
पर्वतान् । दृंहत् । ओजसा । अधराचीनं । अकृणोत् । अपां । अपः । अधारयत् । पृथिवीं । विश्वऽ
धायसं । अस्तभ्नात् । मायया । द्यां । अवऽस्रसः । १० । सः । अस्मै । अरं । बाहुऽभ्यां । यं । पिता । अ
कृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि । येन । पृथिव्यां । नि । क्रिविं । शयध्यै । वज्रेण । ८५

© Dharmartha Trust J&K. Digitized by eGangotri

कृत्वी। अरिणक्। तुविऽस्वनिः। अमाजूःऽइव। पित्रोः। सचा। सती। समानात्। आ। सदसः। त्वां। इ
ये। भगं। कृधि। प्रऽकेतं। उप। मासि। आ। भर। दद्धि। भागं। तन्वः। येन। ममहः। भोजं। त्वां। इंद्र। वयं।
हुवेम। ददिः। त्वं। इंद्र। अपांसि। वाजान्। अविड्ढि। इंद्र। चित्रया। नः। ऊती। कृधि। वृषन्। इंद्र। वस्यसः
नः। ०। प्रातः। रथः। नवः। योजि। सस्निः। चतुःऽयुगः। त्रिऽकशः। सप्तऽरश्मिः। दशऽअरित्रः।
मनुष्यः। स्वःऽसाः। सः। इष्टिऽभिः। मतिऽभिः। रंह्यः। भूत्। ०। प्रथमं। सः। द्वितीयं। उतो इति। तृतीयं।
मनुषः। सः। होता। अन्यस्याः। गर्भं। अन्यः। ऊं इति। जनंत। सः। अन्येभिः। सचते। जेन्यः। वृषा।
हरी इति। नु। कं। रथे। इंद्रस्य। योजं। आऽयै। सुऽउक्तेन। वचसा। नवेन। मो इति। सु। त्वां। अत्र। ब

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ हवं:। हि। विप्राः। नि। रीरमन्। यजमानासः। अन्ये। आ। द्वाभ्यां। हरिऽभ्यां। इंद्र। याहि। आ। चतुःऽभिः

८६ । आ। षट्ऽभिः। हूयमानः। आ। अष्टाभिः। दशऽभिः। सोमऽपेयं। अयं। सुतः। सुऽमख। मा। मृधः। क

रिति कः। आ। विंशत्या। त्रिंशता। याहि। अर्वाङ्। आ। चत्वारिंशता। हरिऽभिः। युजानः। आ। पंचा

86 शता। सुऽरथेभिः। इंद्र। आ। षष्ट्या। सप्तत्या। सोमऽपेयं॥ २३॥ आ। अशीत्या। नवत्या। याहि। अ

र्वाङ्। आ। शतेन। हरिऽभिः। उह्यमानः। अयं। हि। ते। शुनऽहोत्रेषु। सोमः। इंद्र। त्वाऽया। परिऽसिक्तः

मदाय। मम। ब्रह्म। इंद्र। याहि। अच्छ। विश्वा। हरी इति। धुरि। धिष्व। रथस्य। पुरुऽत्रा। हि। विऽहव्यः

। बभूथ। अस्मिन्। शूर। सवने। मादयस्व। न। मे। इंद्रेण। सख्यं। वि। योषत्। अस्मभ्यं। अस्य। ८६

© Dharmartha Trust J&K. Digitized by eGangotri

दक्षिणा। दुहिता। उप। ज्येष्ठे। वरूथे। गभस्तौ। प्रायेऽप्राये। जिगीवांसः। स्याम। ॥ २॥ अपायि। अस्य।
अंधसः। मदाय। मनीषिणः। सुवानस्य। प्रयसः। यस्मिन्। इंद्रः। प्रऽदिवि। ववृधानः। ओकः। दधे। ब्र
ह्मण्यंतः। च। नरः। अस्य। मंदानः। मघवा। वज्रऽहस्तः। अहिं। इंद्रः। अर्णःऽवृतं। वि। वृश्चत्। प्र। यत्। वयः।
न। स्वसराणि। अच्छ। प्रयांसि। च। नदीनां। चक्रमंत। सः। माहिनः। इंद्रः। अर्णः। अपां। प्र। ऐरयत्।
अहिऽहा। अच्छ। समुद्रं। अजनयत्। सूर्यं। विदत्। गाः। अक्तुना। अह्नां। वयुनानि। साधत्। सः।
अप्रतीनि। मनवे। पुरूणि। इंद्रः। दाशत्। दाशुषे। हंति। वृत्रं। सद्यः। यः। नृऽभ्यः। अतसाय्यः। भूत्।
पस्पृधानेभ्यः। सूर्यस्य। सातौ। सः। सुन्वते। इंद्रः। सूर्यं। आ। देवः। रिणक्। मर्त्याय। स्तवान्। आ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ यत्ना।रथ्यं।गुहऽहतऽअवधां।अस्मै।भरन्त।अंशं।न।एतशः।दशऽस्यन्॥२आसः।रंधयत्।सऽदिवः।सा

८७ रथये।शुष्णं।अशुषं।कुयवं।कुत्साय।दिवःऽदासाय।नवतिं।च।नव।इंद्रः।पुरः।वि।ऐरत्।शंबर

87 स्य।एव।ते।इंद्र।उचथं।अहेम।श्रवस्या।न।त्मना।वाजयंतः।अश्याम।तत्।साप्तं।आशुषाणाः।

ननमः।वधः।अदेवस्य।पीयोः।एव।ते।गृत्सऽमदाः।शूर।मन्म।अवस्यवः।न।वयुनानि।तक्षुः

।ब्रह्मण्यंतः।इंद्र।ते।नवीयः।इषं।ऊर्जं।सुऽक्षितिं।सुम्नं।अश्युः॥०॥२१॥वयः।ते।वयः।इंद्र।वि

द्धि।सु।नः।प्र।भरामहे।वाजऽयुः।न।रथं।विपन्यवः।दीध्यतः।मनीषा।सुम्नं।इयक्षंतः।त्वाऽव

तः।नॄन्।त्वं।नः।इंद्र।त्वाभिः।ऊती।त्वाऽयतः।अभिष्टिऽपा।असि।जनान्।त्वं।इनः।दाशुषः।व ८७

ऊता । इत्थाऽधीः । अभि । यः । नक्षति । त्वा । सः । नः । युवा । इंद्रः । जोहूत्रः । सखा । शिवः । नरां । अस्तु । पा

ता । यः । शंसंतं । यः । शशमानं । ऊती । पचंतं । च । स्तुवंतं । च । प्रऽनेषत् । तं । ऊं इति । स्तुषे । इंद्रं । तं । गृणीषे ।

यस्मिन् । पुरा । ववृधुः । शाशदुः । च । सः । वस्वः । कामं । पीपरत् । इयानः । ब्रह्मण्यतः । नूतनस्य । आ

योः । सः । अंगिरसां । उचथा । जुजुष्वान् । ब्रह्म । तूतोत् । इंद्रः । गातुं । इष्णन् । मुष्णन् । उषसः । सूर्येण ।

स्तवान् । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥ २५ ॥ सः । ह । श्रुतः । इंद्रः । नाम । देवः । ऊर्ध्वः । भुवत् ।

मनुषे । दस्मऽतमः । अव । प्रियं । अर्शसानस्य । सह्वान् । शिरः । भरत् । दासस्य । स्वधाऽवान् । सः ।

वृत्रऽहा । इंद्रः । कृष्णऽयोनीः । पुरंऽदरः । दासीः । ऐरयत् । वि । अजनयत् । मनवे । क्षां । अपः । च । स

© Dharmartha Trust J&K. Digitized by eGangotri

प.छि त्रा।शंसा।यजमानस्य।नृतो।त्रानस्मै।तवस्यं।अनु।दायि।सत्रा।इंद्राय।देवेभिः।अर्णऽसातौ।प्रतीय
८८ ना।अस्य।वज्रं।बाह्वोः।धुः।हत्वी।दस्यून्।पुरः।आयसीः।नि।तारीत्।गा।रद्धा।विश्वऽजिते।धनऽजि
ते।स्वःऽजिते।सत्राऽजिते।नृऽजिते।उर्वराऽजिते।अश्वऽजिते।गोऽजिते।अप्ऽजिते।भर।इंद्राय।सो
मं।यजताय।हर्यतं।अभिऽभुवे।अभिःभंगाय।वन्वते।अषाळ्हाय।सहमानाय।वेधसे।तुविऽ
ग्रये।वन्हये।दुस्तरीतवे।सत्राऽसहे।नमः।इंद्राय।वोचत।सत्राऽसहः।जनऽभक्षः।जनंऽसहः।
च्यवनः।युध्मः।अनु।जोषं।उक्षितः।वृतंऽचयः।सहुरिः।विक्षु।आरितः।इंद्रस्य।वोचं।प्र।कृतानि।
वीर्या। [illegible] अननुऽदः।वृषभः।दोधतः।वधः।गंभीरः।ऋष्वः।असमऽष्टऽकाव्यः।रध्रऽचोदः।श्न ८८

88

© Dharmartha Trust J&K. Digitized by eGangotri

थेनः।वी।कितः।पृथुः।इंद्रः।सुऽयज्ञः।उषसः।स्वः।जनत्।यज्ञेन।गातुं।अपऽतुरः।विविद्रिरे।धियः।हि

न्वानाः।उशिजः।मनीषिणः।अभिऽस्वरा।निऽसदा।गाः।अवस्यवः।इंद्रे।हिन्वानाः।द्रविणानि।

आशत।इंद्र।श्रेष्ठानि।द्रविणानि।धेहि।चित्तिं।दक्षस्य।सुभगऽत्वं।अस्मे इति।पोषं।रयीणां।

अरिष्टिं।तनूनां।स्वाद्मानं।वाचः।सुदिनऽत्वं।अन्हां॥ २७॥ त्रिऽकद्रुकेषु।महिषः।यवऽआशि

रं।तुविऽशुष्मः।तृपत्।सोमं।अपिबत्।विष्णुना।सुतं।यथा।अवशत्।सः।ईं।ममाद।महि।

कर्म।कर्त्तवे।महां।उरुं।सः।एनं।सश्चत्।देवः।देवं।सत्यं।इंद्रं।सत्यः।इंदुः।अध।त्विषिऽमान्।

अभि।ओजसा।क्रिविं।युधा।अभवत्।आ।रोदसी इति।अपृणत्।अस्य।मज्मना।प्र।ववृधे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ अधत्त। अन्यं। जठरे। प्र। ईं। अरिच्यत। सा॒कं। जातः। क्रतुना। साकं। ओजसा। ववक्षिथ। साकं। वृद्धः।

८९ वीर्यैः। ससहिः। मृधः। विऽचर्षणिः। दाता। राधः। स्तुवते। काम्यं। वसु।०। नवा। स्यन्ना। नयौन्न्तोइति।

89

अपः। इंद्र। प्रथमं। पूर्व्यं। दिवि। प्रऽवाच्यं। कृतं। यत्। देवस्य। शवसा। प्र। अरिणाः। असुं। रिणन्।

अपः। सुवत्। विश्वं। अभि। अदेवं। ओजसा। विदात्। ऊर्जं। शतऽक्रतुः। विदात्। इषं॥ २। गणा

नां। त्वा। गणऽपतिं। हवामहे। कविं। कवीनां। उपमश्रवःऽतमं। ज्येष्ठऽराजं। ब्रह्मणां। ब्रह्मणः। पते।

आ। नः। शृण्वन्। ऊतिऽभिः। सीद। सदनं। देवाः। चित्। ते। असुर्य। प्रऽचेतसः। बृहस्पते। यज्ञि

यं। भागं। आनशुः। उस्राःऽइव। सूर्यः। ज्योतिषा। महः। विश्वेषां। इत्। जनिता। ब्रह्मणां। असि। ८९

© Dharmartha Trust J&K. Digitized by eGangotri

आ।विऽबाध्य।परिऽरपः।तमांसि।च।ज्योतिष्मंतं।रथं।ऋतस्य।तिष्ठसि।बृहस्पते।भीमं।अमि
त्रऽदम्भनं।रक्षःऽहनं।गोत्रऽभिदं।स्वःऽविदं।सुनीतिऽभिः।नयसि।त्रायसे।जनं।यः।तुभ्यं।दा
शात्।न।तं।अंहः।अश्नवत्।ब्रह्मऽद्विषः।तपनः।मन्युऽमीः।असि।बृहस्पते।महि।तत्।ते।महिऽ
त्वनं।न।तं।अंहः।न।दुःऽइतं।कुतः।चन।न।अरातयः।तितिरुः।न।द्वयाविनः।विश्वाः।इत्।अस्मा
त्।ध्वरसः।वि।बाधसे।यं।सुऽगोपाः।रक्षसि।ब्रह्मणः।पते।त्वं।नः।गोपाः।पथिऽकृत्।विऽ
चक्षणः।तव।व्रताय।मतिऽभिः।जरामहे।बृहस्पते।यः।नः।अभि।ह्वरः।दधे।स्वा।तं।मर्मर्तु।दु
च्छुना।हरस्वती।उत।वा।यः।मर्चयात्।अनागसः।अरातिऽवा।मर्तः।सानुकः।वृकः।बृहस्पते।
नः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰
१०
90

अप। तं। वर्त्तय। पथः। सु॒ऽगः। नः। अस्यै। देव॒ऽवीतये। रु॒धि। त्रा॒तारं॑। त्वा। त॒नूना॑। ह॒वाम॒हे। अव॒ऽस्प
र्तः। अधि॒ऽव॒क्तारं॑। अ॒स्मऽयुं। बृह॑स्पते। देव॒ऽनिदः॑। नि। ब॒र्हय॑। मा। दुः॒ऽएवाः॑। उत्ऽतरं॑। सु॒म्नं। उत्। न
न॒शन्। त्वया॑। व॒यं। सु॒ऽवृधा॑। ब्रह्म॑णः। प॒ते॒। स्पा॒र्हा। वसु॑। म॒नु॒ष्या॑। आ। द॒दी॒म॒हि॒। याः। नः॒। दू॒रे।
त॒ळितः॑। याः। अरा॑तयः। अ॒भि। सन्ति॑। ज॒म्भय॑। ताः। अ॒न॒प्नसः॑। त्वया॑। व॒यं। उ॒त्ऽत॒मं। धी॒म॒हे॒। व
यः॑। बृह॑स्पते। पप्रि॑णा। सस्नि॑ना। यु॒जा। मा। नः॒। दुः॒ऽशंसः॑। अ॒भि॒ऽदि॒प्सुः। ई॒श॒त॒। प्र। सु॒ऽशंसाः॑
म॒तिऽभिः॑। ता॒रि॒षी॒म॒हि॒। ॥३०॥ अ॒नु॒नु॒ऽदः। वृ॒ष॒भः। जग्मिः॑। आ॒ऽह॒वं। निःऽत॒प्ता। शत्रुं॑। पृत॑
नासु। स॒स॒हिः। अ॒सि॒। स॒त्यः। ऋ॒ण॒ऽयाः। ब्रह्म॑णः। प॒ते॒। उ॒ग्रस्य॑। चि॒त्। द॒मि॒ता। वी॒ळु॒ऽह॒र्षिणः॑। १०

© Dharmartha Trust J&K. Digitized by eGangotri

अदेवेन। मनसा। यः। रिषण्यति। शासां। उग्रः। मन्यमानः। जिघांसति। बृहस्पते। मा। प्रणक्। त
स्य। नः। वधः। नि। कर्म। मन्युं। दुःऽएवस्य। शर्धतः। भरेषु। हव्यः। नमसा। उपऽसद्यः। गंता। वाजेषु।
सनिता। धनंऽधनं। विश्वाः। इत्। अर्यः। अभिऽदिप्स्वः। मृधः। बृहस्पतिः। वि। ववर्ह। रथान्ऽइ
व। तेजिष्ठया। तपनी। रक्षसः। तप। ये। त्वा। निदे। दधिरे। दृष्टऽवीर्यं। आविः। तत्। कृष्व। यत्। अस
त्। ते। उक्थ्यं। बृहस्पते। वि। परिऽरपः। अर्दय। बृहस्पते। अति। यत्। अर्यः। अर्हात्। द्युऽमत्।
विऽभाति। क्रतुऽमत्। जनेषु। यत्। दीदयत्। शवसा। ऋतऽप्रजात। तत्। अस्मासु। द्रविणं। धे
हि। चित्रं। १५। मा। नः। स्तेनेभ्यः। ये। अभि। द्रुहः। पदे। निराऽमिणः। रिपवः। अन्नेषु। जगृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ हि॰
९३
91

धुः। आ। देवानां। ओहते। वि। व्रयः। हृदि। बृहस्पते। न। परः। साम्नः। विदुः। विश्वेभ्यः। हि। त्वा। भुव
नेभ्यः। परि। त्वष्टा। अजनत्। साम्नःऽसाम्नः। कविः। सः। ऋणऽचित्। ऋणऽयाः। ब्रह्मणः। पतिः
द्रुहः। हन्ता। महः। ऋतस्य। धर्तरि। तव। श्रिये। वि। आजिहीत। पर्वतः। गवां। गोत्रं। उत्ऽअसृजः।
यत्। अंगिरः। इंद्रेण। युजा। तमसा। परिऽवृतं। बृहस्पते। निः। अपां। औब्जः। अर्णवं। ब्रह्मणः।
पते। त्वं। अस्य। यंता। सुऽउक्तस्य। बोधि। तनयं। च। जिन्व। विश्वं। तत्। भद्रं। यत्। अवंति। देवाः।
१०।।३२।। इति द्वितीयाष्टके पंचमोऽध्यायः।। ।।ॐ।। सेमांषोडशांत्यात्रिष्टुप्द्वादशीचसैंद्री
चैंधानःपंचअगनंत्वसुभ्वतुष्कमिमागिरस्त्र्यूनाकूर्मोगात्संमदोहिवादित्यमिदमेकादश ९३

© Dharmartha Trust J&K. Digitized by eGangotri

वारुणमुपांस्या दुःस्वप्ननाशिनी धतव्रताः सप्त वैश्वदेवं मतमेकादशाक्षागत्यं तेषव्यैंद्रा सोमी सरस्व
तित्वमिति सारस्वतो र्धर्चौ यो नो बार्हस्पत्यां तेवो मारुतस्माकं सप्त वैश्वदेवं त्रिष्टुबंतं मस्य मे ष्टौ जा
गतं त्र्यनुष्टुबंतं द्यावापृथिव्यै काद्वैत्रौ त्वाष्ट्रो बार्हद्रैराकासिनीवाल्यो रंस्यालिंगोक्तदेवतां तेपु
यो नारौद्रं धारावरा मारुतं त्रिष्टुबंतं मुपमपोनग्रीयंतुम्यं षट्कृतव्यं तु जागतं तु॥ ॥ॐ॥ सः। इ
मां। आ। विहि। प्रऽभर्ति। यः। ईशिषे। अया। विधेम। नवया। महा। गिरा। यथा। नः। मीढ्वान्। स्तव
ते। सरखा। तव। बृहस्पते। सीसधः। सः। उत। नः। मतिं। यः। नेत्वानि। अनमत्। नि। ओजसा। उत।
अदर्दः। मन्युना। शंबराणि। वि। प्र। अच्युवयत्। अच्युता। ब्रह्मणः। पतिः। आ। च। अविशत्। व

© Dharmartha Trust J&K. Digitized by eGangotri

१-द्वि सुऽमंतं। विऽपर्वतं। तत्। देवानां। देवऽतमाय। कर्त्वं। अश्रथ्नन्। दृळ्हा। अव्रदंत। वीळिता। उत्। गाः। आ

९२ जत्। अभिनत्। ब्रह्मणा। वलं। अगूहत्। तमः। वि। अचक्षयत्। स्व३रिति स्वः। अश्मऽआस्यं। अव

९२ तं। ब्रह्मणः। पतिः। मधुऽधारं। अभि। यं। ओजसा। अतृणत्। तं। एव। विश्वे। पपिरे। स्वःऽदृशः। ब

हु। साकं। सिसिचुः। उत्सं। उद्रिणं। सना। ता। का। चित्। भुवना। भवीत्वा। मात्ऽभिः। शरत्ऽभिः।

दुरः। वरंत। वः। अयतंता। चरतः। अन्यत्ऽअन्यत्। इत्। या। चकार। वयुना। ब्रह्मणः। पतिः। ३।

अभिऽनक्षंतः। अभि। ये। तं। आनशुः। निऽधिं। पणीनां। परमं। गुहा। हितं। ते। विद्वांसः। प्रतिऽच

क्ष्य। अनृता। पुनः। यतः। ऊं इति। आ। अयन्। तत्। उत्। ईयुः। आऽविशं। ऋतऽवानः। प्रतिऽचक्ष्य। अनृ ९२

© Dharmartha Trust J&K. Digitized by eGangotri

ता । पुनः । आ । अतः । आ । तस्थुः । कवयः । महः । पथः । ते । बाहुऽभ्यां । धमितं । अग्निं । अश्मनि । न
किः । सः । अस्ति । अरणः । जहुः । हि । तं । ऋतऽज्येन । क्षिप्रेण । ब्रह्मणः । पतिः । यत्र । वष्टि । प्र । तत् । अश्नोति ।
धन्वना । तस्य । साध्वीः । इषवः । याभिः । अस्यति । नृऽचक्षसः । दृशये । कर्णऽयोनयः । सः । सम्ऽनु
यः । सः । विऽनयः । पुरःऽहितः । सः । सुऽस्तुतः । सः । युधि । ब्रह्मणः । पतिः । चाक्ष्मः । यत् । वाजं । भरते ।
मती । धना । आत् । इत् । सूर्यः । तपति । तप्यतुः । वृथा । विऽभु । प्रऽभु । प्रथमं । मेहनाऽवतः । बृहस्पतेः
नि २ । सुऽविदत्राणि । राध्या । इमा । साता । वेन्यस्य । वाजिनः । येन । जनाः । उभये । भुंजते । विशः ॥ २ ॥
यः । अवरे । वृजने । विश्वऽथा । विऽभुः । महां । ऊं इति । रण्वः । शवसा । ववक्षिथ । सः । देवः । देवान् ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ प्रति। पप्रथे। पृथु। विश्वा। इत्था। कुऽइत्था। ता। परिऽभूः। ब्रह्मणः। पतिः। विश्वं। सत्यं। मघऽवाना। युवोः। इ

९३ त्। आपः। चन। प्र। मिनंति। व्रतं। वां। अच्छ। इंद्रा। ब्रह्मणस्पती इति। हविः। नः। अन्नं। युजाऽइव। वाजि

93 ना। जिगातं। उत। आशिष्ठाः। अनु। शृण्वंति। वह्नयः। सभेयः। विप्रः। भरते। मती। धना। वीळुऽद्वेषाः

। अनु। वशा। ऋणं। आऽददिः। सः। ह। वाजी। संऽइथे। ब्रह्मणः। पतिः। ब्रह्मणः। पतेः। अभवत्। यथाऽ

पि४ वशं। सत्यः। मन्युः। महि। कर्म। करिष्यतः। यः। गाः। उत्ऽआजत्। सः। दिवे। वि। च। अभजत्। मही

ऽइव। रीतिः। शवसा। असरत्। पृथक्। ब्रह्मणः। पते। सुऽयमस्य। विश्वहा। रायः। स्याम। रथ्यः। वय

स्वतः। वीरेषु। वीरान्। उप। पृंग्धि। नः। त्वं। यत्। ईशानः। ब्रह्मणा। वेषि। मे। हवं ॥ ३ ॥ इंधानः। अ ९३

© Dharmartha Trust J&K. Digitized by eGangotri

ग्निं। वनवत्। वनुष्यतः। कृतऽब्रह्मा। शूशुवत्। रातऽहव्यः। इत्। जातेन। जातं। अति। सः। प्र। सर्स्रे
ते। यंऽयं। युजं। कृणुते। ब्रह्मणः। पतिः। वीरेभिः। वीरान्। वनवत्। वनुष्यतः। गोभिः। रयिं। पप्रथत्।
बोधति। त्मना। तोकं। च। तस्य। तनयं। च। वर्धते। ०। सिंधुः। न। क्षोदः। शिमीऽवान्। ऋघायतः।
वृषाऽइव। वध्रीन्। अभि। वष्टि। ओजसा। अग्नेःऽइव। प्रऽसितिः। न। अह। वर्तवे। ०। तस्मै। अर्षंति।
दिव्याः। असश्चतः। सः। सत्वऽभिः। प्रथमः। गोषु। गच्छति। अनिभृष्टऽतविषिः। हंति। ओजसा।
०। तस्मै। इत्। विश्वाः। धुनयंत। सिंधवः। अच्छिद्रा। शर्म। दधिरे। पुरूणि। देवानां। सुम्ने। सुऽभगः।
सः। एधते। ०। भा। ऋजुः। इत्। शंसः। वनवत्। वनुष्यतः। देवऽयन्। इत्। अदेवऽयंतं। अभि। अस

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ त्।सुप्रऽअवीः।इत्।वनवत्।पृत्ऽसु।दुस्तरं।यज्वा।इत्।अयज्योः।वि।भजाति।भोजनं।यजस्व।वी अ॰१
९४ र।प्र।विहि।मनायतः।भद्रं।मनः।कृणुष्व।वृत्रऽतूर्ये।हविः।कृणुष्व।सुऽभगः।यथा।अससि।ब्रह्म
णः।पतेः।अवः।आ।वृणीमहे।सः।इत्।जनेन।सः।विशा।सः।जन्मना।सः।पुत्रैः।वाजं।भरते।
९४ धना।नृऽभिः।देवानां।यः।पितरं।आऽविवासति।श्रद्धाऽमनाः।हविषा।ब्रह्मणः।पतिं।यः।अस्मै।
हव्यैः।घृतवत्ऽभिः।अविधत्।प्र।तं।प्राचा।नयति।ब्रह्मणः।पतिः।उरुष्यति।ईं।अंहसः।रक्षति
।रिषः।अंहोः।चित्।अस्मै।उरुऽचक्रिः।अद्भुतः।।५।।इमाः।गिरः।आदित्येभ्यः।घृतऽस्नूः।सना
त्।राजऽभ्यः।जुह्वा।जुहोमि।शृणोतु।मित्रः।अर्यमा।भगः।नः।तुविऽजातः।वरुणः।दक्षः।अं ९५

© Dharmartha Trust J&K. Digitized by eGangotri

शः। इमं। स्तोमं। सऽक्रतवः। मे। अद्य। मित्रः। अर्यमा। वरुणः। जुषंत। आदित्यासः। शुचयः। धारऽ
पूताः। अवृजिनाः। अनवद्याः। अरिष्टाः। नो। आदित्यासः। उरवः। गभीराः। अदब्धासः। दिप्संतः। भूरि
रिऽअक्षाः। अंतः। पश्यंति। वृजिना। उत। साधु। सर्वं। राजऽभ्यः। परमा। चित्। अंति। धारयंतः
। आदित्यासः। जगत्। स्थाः। देवाः। विश्वस्य। भुवनस्य। गोपाः। दीर्घऽधियः। रक्षमा
णाः। असुर्यं। ऋतऽवानः। चयमानाः। ऋणानि। विद्यां। आदित्याः। अवसः। वः। अस्य। यत्। अर्य
मन्। भये। आ। चित्। मयःऽभु। युष्माऽकं। मित्रावरुणा। प्रऽनीतौ। परि। श्वभ्राऽइव। दुःऽइतानि।
वृज्यां। ॥५॥ सुऽगः। हि। वः। अर्यमन्। मित्र। पंथाः। अनृक्षरः। वरुण। साधुः। अस्ति। तेन। आदि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ स्युः। अधि। वोचत। नः। यच्छत। नः। दुःऽपरिहन्तु। शर्म। पिपर्तु। नः। अदितिः। राजऽपुत्रा। अति। द्वे
९५ षांसि। अर्यमा। सुऽगेभिः। बृहत्। मित्रस्य। वरुणस्य। शर्म। उप। स्याम। पुरुऽवीराः। अरिष्टाः।
95 तिस्रः। भूमीः। धारयन्। त्रीन्। उत। द्यून्। त्रीणि। व्रता। विदथे। अंतः। एषां। ऋतेन। आदित्याः। म
हि। वः। महिऽत्वं। तत्। अर्यमन्। वरुण। मित्र। चारु। त्री। रोचना। दिव्या। धारयंत। हिरण्ययाः। शु
चयः। धारऽपूताः। अस्वप्नऽजः। अनिऽमिषाः। अदब्धाः। उरुऽशंसाः। ऋजवे। मर्त्याय। त्वं। विश्वेषां
। वरुण। असि। राजा। ये। च। देवाः। असुर। ये। च। मर्ताः। शतं। नः। रास्व। शरदः। विऽचक्षे। अश्या
म। आयूंषि। सुऽधितानि। पूर्वा। ॥७॥ न। दक्षिणा। वि। चिकिते। न। सव्या। न। प्राचीनं। आदित्याः। ९५

© Dharmartha Trust J&K. Digitized by eGangotri

न।उत।पश्चा।पाक्या।चित्ता।वसवः।धीर्या।चित्ता।युष्माऽनीतः।अभयं।ज्योतिः।अश्यां।यः।राजऽ
भ्यः।ऋतनिऽभ्यः।ददाश।यं।वर्द्धयंति।पुष्टयः।च।नित्याः।सः।रेवान्।याति।प्रथमः।रथेन।वसुऽ
दावा।विदथेषु।प्रऽशस्तः।शुचिः।अपः।सुऽयवसाः।अदब्धः।उप।क्षेति।वृद्धऽवयाः।सुऽवीरः।न
किः।तं।घ्नंति।अंतितः।न।दूरात्।यः।आदित्यानां।भवति।प्रऽनीतौ।अदिते।मित्र।वरुण।उत।मृ
ळ।यत्।वः।वयं।चकृम।कत्।चित्।आगः।उरु।अश्यां।अभयं।ज्योतिः।इंद्र।मा।नः।दीर्घाः।अभि।
नशन्।तमिस्राः।उभेइति।अस्मै।पीपयतः।समीचीइति।संऽईची।दिवः।वृष्टिं।सुऽभगः।नाम।
पुष्यन्।उभा।क्षयौ।आऽजयन्।याति।पृत्ऽसु।उभौ।अर्द्धौ।भवतः।साधूइति।अस्मै।यः।वः।मा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ दि॰ याः। अभिऽद्रुहे। यजत्राः। पाशाः। आदित्याः। रिपवे। विऽचृत्ताः। अश्वीऽइव। तान्। अति। येषं। रथेन।
९६ अरिष्टाः। उरौ। आ। शर्मन्। स्याम। मा। अहं। मघोनः। वरुण। प्रियस्य। भूरिऽदाव्नः। आ। विदं। शूनं।
आपेः। मा। रायः। राजन्। सुऽयमात्। अव। स्थां। ॥ ॥ इदं। कवेः। आदित्यस्य। स्वऽराजः। विश्वानि।
96 सन्ति। अभि। अस्तु। मह्ना। अति। यः। मंद्रः। यजथाय। देवः। सुऽकीर्तिं। भिक्षे। वरुणस्य। भूरेः।
तव। व्रते। सुऽभगासः। स्याम। सुऽआध्यः। वरुण। तुस्तुऽवांसः। उपऽअयने। उषसां। गोमतीनां।
अग्नयः। न। जरमाणाः। अनु। द्यून्। तव। स्याम। पुरुऽवीरस्य। शर्मन्। उरुऽशंसस्य। वरुण। प्र
नेतरिति प्रऽनेतः। यूयं। नः। पुत्राः। अदितेः। अदब्धाः। अभि। क्षमध्वं। युज्याय। देवाः। प्र। सीं। आ ९६

© Dharmartha Trust J&K. Digitized by eGangotri

दियः। असृजत। वि। धर्त्ता। ऋतं। सिंधवः। वरुणस्य। यंति। न। श्राम्यंति। न। वि। मुचंति। एते। वयः। न

पप्तुः। रघुऽया। परि। ज्मन्। वि। मत्। श्रथय। रशनांऽइव। आगः। ऋध्याम। ते। वरुण। खां। ऋतस्य।

मा। तंतुः। छेदि। वयतः। धियं। मे। मा। मात्रा। शारि। अपसः। पुरा। ऋतोः। ५। अपो इति। सु। म्यक्ष

वरुण। भियसं। मत्। संऽराट्। ऋतऽवः। अनु। मा। गृभाय। दामऽइव। वत्सात्। वि। मुमुग्धि। अंहः।

नहि। त्वत्। आरे। निऽमिषः। चन। ईशे। मा। नः। वधैः। वरुण। ये। ते। इष्टौ। एनः। कृण्वंतं। असुर। भ्री

णंति। मा। ज्योतिषः। प्रऽवसथानि। गन्म। वि। सु। मृधः। शिश्रथः। जीवसे। नः। नमः। पुरा। ते। व

रुण। उत। नूनं। उत। अपरं। तुविऽजात। ब्रवाम। त्वे इति। हि। कं। पर्वते। न। श्रितानि। अप्रऽच्युतानि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ दुःऽदभान्। व्रतानि। परा। ऋणा। सावीः। अध। मत्ऽकृतानि। मा। अहं। राजन्। अन्यऽकृतेन। भोजं। अ
९७ विऽउष्टाः। इत्। नु। भूयसीः। उषसः। आ। नः। जीवान्। वरुण। तासु। शाधि। यः। मे। राजन्। युज्यः। वा।
97 सखा। वा। स्वप्ने। भयं। भीरवे। मह्यं। आह। स्तेनः। वा। यः। दिप्सति। नः। वृकः। वा। त्वं। तस्मात्। वरु
ण। पाहि। अस्मान्॥ १०॥ ३०॥ धृतऽव्रताः। आदित्याः। इषिराः। आरे। मत्। कर्त। रहसूःऽइव। आगः।
शृण्वतः। वः। वरुण। मित्र। देवाः। भद्रस्य। विद्वान्। अवसे। हुवे। वः। यूयं। देवाः। प्रऽमतिः। यूयं।
ओजः। यूयं। द्वेषांसि। सनुतः। युयोत। अभिऽक्षत्तारः। अभि। च। क्षमध्वं। अद्य। च। नः। मृळ
यत। अपरं। च। किं। ऊं इति। नु। वः। कृणवाम। अपरेण। किं। सनेन। वसवः। आप्येन। यूयं। नः। ९७

© Dharmartha Trust J&K. Digitized by eGangotri

मित्रावरुणा। अदिते। च। स्वस्ति। इन्द्रामरुतः। दधात। हये। देवाः। यूयं। इत्। आपयः। स्थ। ते। मृळत। नाध
मानाय। मह्यं। मा। वः। रथः। मध्यमऽवाट्। ऋते। भूत्। मा। युष्मावत्ऽसु। आपिषु। श्रमिष्म। प्र। वः। ए
कः। मिमय। भूरि। आगः। यत्। मा। पिताऽइव। कितवं। शशास। आरे। पाशाः। आरे। अघानि। देवाः।
मा। मा। अधि। पुत्रे। विंऽइव। ग्रभीष्ट। अर्वाञ्चः। अद्य। भवत। यजत्राः। आ। वः। हार्दि। भयमानः। व्यये
यं। त्राध्वं। नः। देवाः। निऽजुरः। वृकस्य। त्राध्वं। कर्तात्। अवऽपदः। यजत्राः॥ ३३॥ ऋतं। देवाय। कृण्व
ते। सवित्रे। इन्द्राय। अहिऽघ्ने। न। रमन्ते। आपः। अहःऽअहः। याति। अक्तुः। अपां। कियति। आ। प्रथमः।
सर्गः। आसां। यः। वृत्राय। सिनं। अत्र। अभरिष्यत्। प्र। तं। जनित्री। विदुषे। उवाच। पथः। रदन्तीः। अनु।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि
१८
98

य
जोषं। अस्मै। दिवेऽदिवे। धुनेः। यंति। अर्थं। ऊर्ध्वः। हि। अस्थात्। अधि। अंतरिक्षे। अध। वृत्राय। प्र। व
धं। जभार। मिहं। वसानः। उप। हि। ईं। अदुद्रोत्। तिग्मऽआयुधः। अजयत्। शत्रुं। इंद्रः। बृहस्पते। तपु
षा। अश्नाऽइव। विध्य। वृकऽद्वरसः। असुरस्य। वीरान्। यथा। जघंथ। धृषता। पुरा। चित्। एव। जहि।
शत्रुं। अस्माकं। इंद्र। अव। क्षिप। दिवः। अश्मानं। उच्चा। येन। शत्रुं। मंदसानः। निऽजूर्वाः। तोकस्य। सा
तौ। तनयस्य। भूरेः। अस्मान्। अर्धं। कृणुतात्। इंद्र। गोनां॥ ३ ॥ प्र। हि। क्रतुं। वृहथः। यं। वनुथः। रध्र
स्य। स्थः। यजमानस्य। चोदौ। इंद्र। सोमा। युवं। अस्मान्। अविष्टं। अस्मिन्। भयऽस्थे। कृणुतं। ऊं इति।
लोकं। न। मा। तमत्। न। श्रमत्। उत। तंद्रत्। न। वोचाम। मा। सुनोत। इति। सोमं। यः। मे। पृणात्। यः। १८
नः।

© Dharmartha Trust J&K. Digitized by eGangotri

दद्नत्। यः। निऽद्रोधात्। यः। मा। सुन्वंतं। उप। गोभिः। आ। अयत्। सरस्वति। त्वं। अस्मान्। अविड्ढि। मरुत्व
ती। धृषती। जेषि। शत्रून्। त्यं। चित्। शर्धंतं। तविषीऽयमाणं। इंद्रः। हंति। वृषभं। शंडिकानां। यः। नः। स
नुऽत्यः। उत। वा। जिघत्नुः। अभिऽख्याय। तं। तिगितेन। विध्य। बृहस्पते। आयुधैः। जेषि। शत्रून्। द्रुहे।
रिषंतं। परि। धेहि। राजन्। अस्माकेभिः। सत्वऽभिः। शूर। शूरैः। वीर्या। कृधि। यानि। ते। कर्त्वानि। ज्यो।
क्। अभूवन्। अनुऽधूपिता। सः। हत्वी। तेषां। आ। भर। नः। वसूनि। तं। वः। शर्धं। मारुतं। सुम्नऽयुः। गि
रा। उप। ब्रुवे। नमसा। दैव्यं। जनं। यथा। रयिं। सर्वऽवीरं। नशामहै। अपत्यऽसाचं। श्रुत्यं। दिवेऽदिवे॥ ३३॥
अस्माकं। मित्रावरुणा। अवतं। रथं। आदित्यैः। रुद्रैः। वसुऽभिः। सचाऽभुवा। प्र। यत्। वयः। न। पप्तन्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ वस्मे।नः।परि।ऋव।स्यवः।हवीवंतः।वनःऽसदः।अध।स्म।नः।उत।अवत।सऽजोषसः।रथं।देवासः।अ

११ भि।विक्षु।वाजऽयुं।यत्।आशवः।पद्याभिः।तित्रतः।रजः।पृथिव्याः।सानौ।जंघनंत।पाणिऽभिः।उत।

स्यः।नः।इंद्रः।विश्वऽचर्षणिः।दिवः।शर्द्धेन।मारुतेन।सुऽक्रतुः।अनु।नु।स्थाति।अवृकाभिः।ऊतिऽभिः

99 ।रथं।महे।सनये।वाजऽसातये।उत।स्यः।देवः।भुवनस्य।सक्षणिः।त्वष्टा।ग्नाभिः।सऽजोषाः।जूजु

वत्।रथं।इळा।भगः।बृहत्ऽदिवा।उत।रोदसीइति।पूषा।पुरंऽधिः।अश्विनौ।अध।पतीइति।उत।त्ये

इति।देवीइति।सुभगेइति।सुऽभगे।मिथुऽदृशा।उषसानक्ता।जगतां।अपिऽजुवा।स्तुषे।यत्।वां।पृ

थिवि।नव्यसा।वचः।स्थातुः।च।वयः।त्रिऽवयाः।उपऽस्तिरे।उत।वः।शंसं।उशिजांऽइव।श्मसि।अहिः। ११

© Dharmartha Trust J&K. Digitized by eGangotri

बुध्न्यः। अजः। एकऽपात्। उत। त्रितः। ऋभुक्षाः। सविता। चनः। दधे। अपां। नपात्। आशुऽहेमा। धिया।
शमि। एता। वः। वश्मि। उत्ऽयता। यजत्राः। अतक्षन्। आयवः। नव्यसे। सं। श्रवस्यवः। वाजं। चकानाः।
सप्तिः। न। रथ्यः। अह। धीतिं। अश्याः।।३७।। अस्य। मे। द्यावापृथिवी इति। ऋतऽयतः। भूतं। अवित्री इ
ति। वचसः। सिसासतः। ययोः। आयुः। प्रऽतरं। ते इति। इदं। पुरः। उपस्तुते इत्युपऽस्तुते। वसुऽयुः। वां। म
हः। दधे। मा। नः। गुह्याः। रिपः। आयोः। अहन्। दभन्। मा। नः। आभ्यः। रीरधः। दुच्छुनाभ्यः। मा। नः। वि।
यौः। सख्या। विद्धि। तस्य। नः। सुम्नऽयता। मनसा। तत्। त्वा। ईमहे। अहेळता। मनसा। श्रुष्टिं। आ। व
ह। दुहानां। धेनुं। पिप्युषीं। असश्चतं। पद्याभिः। आशुं। वचसा। च। वाजिनं। त्वां। हिनोमि। पुरुऽहूत।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ दि॰ विभ्वहा।राकां।अहं।सुऽहवां।सुऽस्तुती।हुवे।शृणोतु।नः।सुऽभगा।बोधतु।त्मना।सीव्यतु।अपः।सुच्या।
१०० अछिद्यमानया।ददातु।वीरं।शतऽदायं।उक्थ्यं।याः।ते।राके।सुऽमतयः।सुऽपेशसः।याभिः।ददासि।
दाशुषे।वसूनि।ताभिः।नः।अद्य।सुऽमनाः।उपऽआगहि।सहस्रऽपोषं।सुऽभगे।रराणा।सिनीवालि।
100 पृथुऽस्तुके।या।देवानां।असि।स्वसा।जुषस्व।हव्यं।आऽहुतं।प्रऽजां।देवि।दिदिड्ढि।नः।या।सुऽबाहुः।
सुऽअंगुरिः।सुऽसूमा।बहुऽसूवरी।तस्यै।विश्पत्न्यै।हविः।सिनीवाल्यै।जुहोतन।या।गुंगूः।या।
सिनीवाली।या।राका।या।सरस्वती।इंद्राणीं।अह्वे।ऊतये।वारुणानीं।स्वस्तये।१८।आ।ते।पि
तः।मरुतां।सुम्नं।एतु।मा।नः।सूर्यस्य।संऽदृशः।युयोथाः।अभि।नः।वीरः।अर्वति।क्षमेत।प्र।जा १००

© Dharmartha Trust J&K. Digitized by eGangotri

येमहि। रुद्र। प्रऽजाभिः। त्वाऽदत्तेभिः। रुद्र। शंऽतमेभिः। शतं। हिमाः। अशीय। भेषजेभिः। वि। अस्मत्। द्वेषः।
विऽतरं। वि। अंहः। वि। अमीवाः। चातयस्व। विषूचीः। श्रेष्ठः। जातस्य। रुद्र। श्रिया। असि। तवःऽतमः।
तवसां। वज्रबाहो इति वज्रऽबाहो। पर्षि। नः। पारं। अंहसः। स्वस्ति। विश्वाः। अभिऽईतीः। रपसः। युयो
धि। मा। त्वा। रुद्र। चुक्रुधाम। नमःऽभिः। मा। दुःऽस्तुती। वृषभ। मा। सऽहूती। उत्। नः। वीरान्। अर्पय। भे
षजेभिः। भिषक्ऽतमं। त्वा। भिषजां। शृणोमि। हवीमऽभिः। हवते। यः। हविःऽभिः। अव। स्तोमेभिः। रु
द्रं। दिषीय। कूदरः। सुऽहवः। मा। नः। अस्यै। बभ्रुः। सुऽशिप्रः। रीरधत्। मनायै। इति। उत्। मा। ममंद
। वृषभः। मरुत्वान्। त्वक्षीयसा। वयसा। नाधमानं। घृणिःऽइव। छायां। अरपाः। अशीय। आ। विवासे

© Dharmartha Trust J&K. Digitized by eGangotri

१०६ः यं। रुद्रस्य। सुम्नं। कौ। स्यः। ते। रुद्र। मृळयाकुः। हस्तः। यः। अस्ति। भेषजः। जलाषः। अपऽभर्ता। रपसः।
३०३ दैव्यस्य। अभि। नु। मा। वृषभ। चक्षमीथाः। प्र। बभ्रवे। वृषभाय। श्वितीचे। महः। महीं। सुऽस्तुतिं। ईर
याम्। नमस्य। कल्मलीकिनं। नमःऽभिः। गृणीमसि। त्वेषं। रुद्रस्य। नाम। स्थिरेभिः। अंगैः। पुरुऽरूपः।
उग्रः। बभ्रुः। शुक्रेभिः। पिपिशे। हिरण्यैः। ईशानात्। अस्य। भुवनस्य। भूरेः। न। वै। ऊं इति। योषत्। रु
द्रात्। असुर्यं। अर्हन्। बिभर्षि। सायकानि। धन्व। अर्हन्। निष्कं। यजतं। विश्वऽरूपं। अर्हन्। इदं। दय
से। विश्वं। अभ्वं। न। वै। ओजीयः। रुद्र। त्वत्। अस्ति। ११। स्तुहि। श्रुतं। गर्तऽसदं। युवानं। मृगं। न।
भीमं। उपऽहत्नुं। उग्रं। मृळ। जरित्रे। रुद्र। स्तवानः। अन्यं। ते। अस्मत्। नि। वपंतु। सेनाः। कुमारः। पि २०६

© Dharmartha Trust J&K. Digitized by eGangotri

ता।पितरं।वंदमानं।प्रति।ननाम।रुद्र।उपऽयंतं।भूरेः।दातारं।सत्ऽपतिं।गृणीषे।स्तुतः।त्वं।भेषजा।
रासि।अस्मे इति।या।वः।भेषजा।मरुतः।शुचीनि।या।शंऽतमा।वृषणः।या।मयःऽभु।यानि।मनुः।अ
वृणीत।पिता।नः।ता।शं।च।योः।च।रुद्रस्य।वश्मि।परि।नः।हेतिः।रुद्रस्य।वृज्याः।परि।त्वेषस्य।दुः
मतिः।मही।गात्।अव।स्थिरा।मघवत्ऽभ्यः।तनुष्व।मीढ्वः।तोकाय।तनयाय।मृळ।एव।बभ्रो इति।
वृषभ।चेकितान।यथा।देव।न।हृणीषे।न।हंसि।हवनऽश्रुत्।नः।रुद्र।इह।बोधि।०।१५।धाराऽवराः।
मरुतः।धृष्णुऽओजसः।मृगाः।न।भीमाः।तविषीभिः।अर्चिनः।अग्नयः।न।शुशुचानाः।ऋजीषि
णः।भृमिं।धमंतः।अप।गाः।अवृण्वत।द्यावः।न।स्तृऽभिः।चितयंत।खादिनः।वि।अभ्रियाः।न।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ द्युतयंत। दृह्यवः। रुद्राः। यता। वः। मरुतः। रुक्मऽवक्षसः। वृषा। अजनि। पृश्न्याः। शुक्रः। ऊधनि। तुक्षं
१०२ तैः। अश्वाः न। अस्याः नःऽइव। आजिषु। नदस्य। कर्णैः। तुरयंते। आशुऽभिः। हिरण्यऽशिप्राः। मरुतः। दवि १२
ध्वतः। पृक्षं। याथ। पृषतीभिः। सऽमन्यवः। पृक्षे। ना। विश्वा। भुवना। ववक्षिरे। मित्राय। वा। सदं
आ। जीरऽदानवः। पृषत्ऽअश्वासः। अनवभ्रऽराधसः। ऋजिप्यासः। न। वयुनेषु। धूःऽसदः। इधन्वऽ
भिः। धेनुऽभिः। रप्शत्ऽऊधऽभिः। अध्वस्मऽभिः। पथिऽभिः। भ्राजत्ऽऋष्टयः। आ। हंसासः। न। स्वसरा
णि। गंतन। मधोः। मदाय। मरुतः। सऽमन्यवः। ॥ ३॥ आ। नः। ब्रह्माणि। मरुतः। सऽमन्यवः। नरां। न।
शंसः। सवनानि। गंतन। अश्वांऽइव। पिप्यत। धेनुं। ऊधनि। कर्त। धियं। जरित्रे। वाजऽपेशसं। १०२

© Dharmartha Trust J&K. Digitized by eGangotri

नेः। नः। दात। मरुतः। वाजिनं। रथे। आपानं। ब्रह्म। चितयत्। दिवेऽदिवे। इषं। स्तोतृऽभ्यः। वृजनेषु। कारवे। सनिं। ने
मधां। अरिष्टं। दुस्तरं। सहः। यत्। युंजते। मरुतः। रुक्मऽवक्षसः। अश्वान्। रथेषु। भगे। आ। सुऽदानवः। धे
नुः। न। शिश्वे। स्वसरेषु। पिन्वते। जनाय। रातऽहविषे। महीं। इषं। यः। नः। मरुतः। वृकऽताति। मर्त्यः। रिपुः। द नुः।
न धे। वसवः। रक्षत। रिषः। वर्त्तयत। तपुषा। चक्रिया। अभि। तं। अव। रुद्राः। अशसः। हंतन। वधः। चित्रं।
तत्। वः। मरुतः। याम। चेकिते। पृश्न्याः। यत्। ऊधः। अपि। आपयः। दुहुः। यत्। वा। निदे। नवमानस्य। रु
द्रियाः। त्रितं। जराय। जुरतां। अदाभ्याः॥ २॥ तान्। वः। महः। मरुतः। एवऽयाव्नः। विष्णोः। एषस्य। प्रऽ
भृथे। हवामहे। हिरण्यऽवर्णान्। ककुहान्। यतऽस्रुचः। ब्रह्मण्यंतः। शंस्यं। राधः। ईमहे। ते। दशऽग्वाः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ प्रथमाः। यज्ञं। ऊ॒र्ध्वे॒ इ॒हि॒रे। ते। नः। हि॒न्वं॒तु॒। उ॒षसः। वि॒ऽउ॑ष्टिषु। उ॒षाः। न। रा॒मीः। अ॒रु॒णैः। अप॑। ऊ॒र्णु॒ते। म॒हः। ज्यो
३०३ तिषा। शु॒च॒ता। गोः। अर्णसा। ते। क्षो॒णी॒भिः। अ॒रु॒णे॒भिः। न। अं॒जि॒ऽभिः। रु॒द्राः। ऋ॒तस्य। सद॑नेषु। व॒वृ॒धुः
103 ।नि॒ऽमे॒घमा॑नाः। अत्ये॑न। पाजसा। सु॒ऽचं॒द्रं। वर्णं। द॒धि॒रे। सु॒ऽपेशसं। ता। न॒। इ॒ऽया॒नः। म॒हि। व॒रू॒थं। ऊ॒त
ये। उप॑। घ॒। इ॒ता॒। ए॒ना॒। न॒मसा। गृ॒णी॒म॒सि॒। त्रि॒तः। न। या॒न्। पंच॑। होतॄ॑न्। अ॒भि॒ष्टये॑। आ॒ऽव॒वर्त॑त्। अ
वरा॑न्। च॒क्रिया॑। अव॑से। यया॑। र॒ध्रं॑। पा॒रय॑थ। अति॑। अंहः॑। यया॑। नि॒दः। मु॒ंचथ। वं॒दि॒तारं॑। अ॒र्वा॒ची
सा। म॒रु॒तः। या। वः। ऊ॒तिः। ओ॒ऽइ॒ति। सु। वा॒श्राऽइ॑व। सु॒ऽम॒तिः। जिगा॑तु। र॒ण्वा। उप॑। ई॒। अस्र॑क्षि। वा॒जऽयुः।
व॒च॒स्यां। व॒नैः। द॒धी॒त। ना॒धः। गिरः॑। मे॒। अ॒पां। न॒पा॒त्। आ॒शु॒ऽहेमा॑। कु॒वित्। सः। सु॒ऽपेश॑सः। क॒र॒ति॒। ३०३

© Dharmartha Trust J&K. Digitized by eGangotri

नोषित्। हि। इमं। सु। अस्मै। हृदः। आ। सुऽतष्टं। मंत्रं। वोचेम। कुवित्। अस्य। वेदत्। अपां। नपात्। असु
र्यस्य। मन्हा। विश्वानि। अर्यः। भुवना। जजान। सं। अन्याः। यंति। उप। यंति। अन्याः। समानं। ऊर्वं। न
द्यः। पृणंति। तं। ऊं इति। शुचिं। शुचयः। दीदिऽवांसं। अपां। नपातं। परि। तस्थुः। आपः। तं। अस्मेराः। युव
तयः। युवानं। मर्मृज्यमानाः। परि। यंति। आपः। सः। शुक्रेभिः। शिक्वऽभिः। रेवत्। अस्मे इति। दीदाय।
अनिध्मः। घृतऽनिर्निक्। अप्ऽसु। अस्मै। तिस्रः। अव्यथ्याय। नारीः। देवाय। देवीः। दिधिषंति। अ
न्नं। कृताःऽइव। उप। हि। प्रऽसस्रे। अप्ऽसु। सः। पीयूषं। धयति। पूर्वऽसूनां। २२। अश्वस्य। अत्र। ज
निम। अस्य। च। स्वः। द्रुहः। रिषः। संऽपृचः। पाहि। सूरीन्। आमासु। पूर्षु। परः। अप्रऽमृष्यं। न। अरा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ तयः। वि। नशन्। न। अनृता। नि। स्वे। आ। दमे। सुऽदुघा। यस्य। धेनुः। स्वधां। पीपाय। सुऽभु। अन्नं। अत्ति।
१०४ सः। अपां। नपात्। ऊर्जयन्। अप्ऽसु। अंतः। वसुऽदेयाय। विधते। वि। भाति। यः। अप्ऽसु। आ। शुचिना।
दैव्येन। ऋतऽवा। अजस्रः। उर्विया। विऽभाति। वयाः। इत्। अन्याः। भुवनानि। अस्य। प्र। जायंते। वीरुधः।
च। प्रऽजाभिः। अपां। नपात्। आ। हि। अस्थात्। उपऽस्थं। जिह्मानां। ऊर्ध्वः। विऽद्युतं। वसानः। तस्य। ज्ये
ष्ठं। महिमानं। वहंतीः। हिरण्यऽवर्णाः। परि। यंति। यह्वीः। हिरण्यऽरूपः। सः। हिरण्यऽसंदृक्। अपां।
नपात्। सः। इत्। ऊं इति। हिरण्यऽवर्णः। हिरण्ययात्। परि। योनेः। निऽसद्य। हिरण्यऽदाः। ददति। अ
न्नं। अस्मै॥ २३॥ तत्। अस्य। अनीकं। उत। चारु। नाम। अपीच्यं। वर्धते। नप्तुः। अपां। यं। इंधते। युवत १०५

© Dharmartha Trust J&K. Digitized by eGangotri

यः । सं । इत्था । हिरण्यऽवर्णं । घृतं । अन्नं । अस्य । अस्मै । बहूनां । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा । ह
विःऽभिः । सं । सानु । मार्ज्मि । दिधिषामि । बिल्मैः । दधामि । अन्नैः । परि । वंदे । ऋक्ऽभिः । सः । ईं । वृषा । अजन
यत् । तासु । गर्भं । सः । ईं । शिशुः । धयति । तं । रिहंति । ० । अनभिम्लातऽवर्णः । अन्यस्यऽइव । तन्वा । विवेष । इह ।
मे ४ अस्मिन् । पदे । परमे । तस्थिऽवांसं । अध्वस्मऽभिः । विश्वहा । दीदिऽवांसं । आपः । नप्त्रे । घृतं । अन्नं । वहंतीः ।
स्वयं । अत्कैः । परि । दीयंति । यह्वीः । अयांसं । अग्ने । सुऽक्षितिं । जनाय । अयांसं । ऊं इति । मघवत्ऽभ्यः ।
सुऽवृक्तिं । ० । २५ । तुभ्यं । हिन्वानः । वसिष्ठ । गाः । अपः । अधुक्षन् । सीं । अविऽभिः । अद्रिऽभिः । नरः । पि
ब । इंद्र । स्वाहा । प्रऽहुतं । वषट्ऽकृतं । होत्रात् । आ । सोमं । प्रथमः । यः । ईशिषे । यज्ञैः । संऽमिश्लाः । पृषती

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ मिः। ऋष्टिऽमिः। यामन्। शुभ्रासः। अंजिषु। प्रियाः। उत। आ। सद्यो। बर्हिः। भरतस्य। सूनवः। पोत्रात्। आ।
१०५ सोमं। पिबत। दिवः। नरः। अमाऽइव। नः। सुऽहवाः। आ। हि। गंतन। नि। बर्हिषि। सदतन। रणिष्टन। अथ।
105 मंदस्व। जुजुषाणः। अंधसः। त्वष्टः। देवेभिः। जनिऽभिः। सुमत्ऽगणः। आ। वक्षि। देवान्। इह। विप्राय।
क्षि। च। उशन्। होतः। नि। सद। योनिषु। त्रिषु। प्रति। वीहि। प्रऽस्थितं। सोम्यं। मधु। पिब। आग्नीध्रात्।
तव। भागस्य। तृप्णुहि। एषः। स्यः। ते। तन्वः। नृम्णऽवर्धनः। सहः। ओजः। प्रऽदिवि। बाह्वोः। हितः।
तुभ्यं। सुतः। मघऽवन्। तुभ्यं। आऽभृतः। त्वं। अस्य। ब्राह्मणात्। आ। तृपत्। पिब। जुषेथां। यज्ञं। बोध
तं। हवस्य। मे। [illegible] सत्तः। होता। निःऽविदः। पूर्व्याः। अनु। अच्छ। राजाना। नमः। एति। आऽवृतं। प्र १०५

शास्त्रात्॥ आ॥ पिब तं॥ सोम्यं॥ मधु॥ २५॥ इति द्वितीयाष्टके सप्तमोध्यायः॥ ॥ॐ॥ मंद स्वादुर्व्यल
कादश सावित्रं गा वाणेया श्वाविनं सोमापूषणा षट् सोमा पोष्णं संयोर्धचौष्यदितें यो यो सेका
गायत्रम् ऊ क्रा देवताः प्रउगेणाद्येनुतरं चैसैंद्रवायवी द्यावापृथिव्यौ सरस्वत्योहाविर्धानोयांन्त्तीयः पादो
वाग्नेयौ वितमेनुष्टुभौ वृहती चैकनिक्रदत्तं चंप्रदक्षिणिज्जागतं मध्ये निशाकर्यष्टिवैनाभ्या मृषिर
ध्यानिवाश्यमानं शाकुं तं तुष्टाव कुशिकस्त्वैषीरथिरिंद्रतुल्यं पुत्रमिछन् ब्रह्मचर्यं चचार तस्येंद्र एव गा
थीपुत्रो जज्ञे गाथिनो विश्वामित्रः स तृतीयं मंडलमपश्यत् सोमस्य मा ध्यधिका वैश्वानराय पंचोना वै
श्वानरीयं तु जागतं तु वैश्वानरायैकादश समित्समिदग्निः प्रत्याग्निः प्रकारवद्द्व साग्नेय योरन्यास

© Dharmartha Trust J&K. Digitized by eGangotri

प.द्वि मपि निपातो दृश्यते ॥ ॐ ॥ मंदस्व । होत्रात् । अनु । जोषं । अंधसः । अध्वर्यवः । सः । पूर्णां । वष्टि । आ । सिंचत ।
३.६ तस्मै । एतं । भरत । तत्ऽवशः । ददिः । होत्रात् । सोमं । द्रविणःऽदः । पिब । ऋतुऽभिः ॥ यं । ऊं इति । पूर्वं । अहुवे । तं । इदं ।
हुवे । सः । इत् । ऊं इति । हव्यः । ददिः । यः । नाम । पत्यते । अध्वर्युऽभिः । प्रऽस्थितं । सोम्यं । मधु । पोत्रात् । ० मेद्यंतु ।
ते । वह्नयः । येभिः । ईयसे । अरिषण्यन् । वीळयस्व । वनस्पते । आऽयूय । धृष्णो इति । अभिऽगूर्य । त्वं । नेष्ट्रा
त् । अपात् । होत्रात् । उत । पोत्रात् । अमत्त । उत । नेष्ट्रात् । अजुषत । प्रयः । हितं । तुरीयं । पात्रं । अमृक्तं । अम
र्त्यं । द्रविणःऽदाः । पिबतु । द्राविणःऽदसः ॥ अर्वांचं । अद्य । यय्यं । नृऽवाहणं । रथं । युंजाथां । इह । वां । विऽमोच
नं । पृंक्तं । हवींषि । मधुना । आ । हि । कं । गतं । अथ । सोमं । पिबतं । वाजिनीवसू इति वाजिनीऽवसू । जोषि । ३.६

अग्ने। सं ऽ इधं। जोषि। आऽहुतिं। जोषि। ब्रह्म। जन्यं। जोषि। सुऽस्तुतिं। विश्वेभिः। विश्वान्। ऋतुना। वसो
इति। महः। उशन्। देवान्। उशतः। पायय। हविः॥३॥ उत्। ऊं इति। स्यः। देवः। सविता। सवाय। शश्वत्ऽत
मं। तत्ऽअपाः। वह्निः। अस्थात्। नूनं। देवेभ्यः। वि। हि। धाति। रत्नं। अथ। आ। अभजत्। वीतिऽहोत्रं।
स्वस्तौ। विश्वस्य। हि। श्रुष्टये। देवः। ऊर्ध्वः। प्र। बाहवा। पृथुऽपाणिः। सिसर्त्ति। आपः। चित्। अस्य। व्र
आ। ते। आ। निऽमृग्राः। अयं। चित्। वातः। रमते। परिऽज्मन्। आशुऽभिः। चित्। यान्। वि। मुचाति। नूनं। अरी
रमत्। अतमानं। चित्। एतोः। अह्यर्षूणां। चित्। नि। अयान्। अविष्यां। अनु। व्रतं। सवितुः। मोकी।
आ। अगात्। पुनरिति। सं। अव्यत्। विऽततं। वयंती। मध्या। कर्त्तोः। नि। अधात्। शक्म। धीरः। उ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ त्। संऽहाय। अस्थात्। वि। ऋतून्। अदर्धः। अरमतिः। सविता। देवः। आ। अगात्। नाना। ओकांसि।
१०७ दुर्यः। विश्वं। आयुः। वि। तिष्ठते। प्रऽभवः। शोकः। अग्नेः। ज्येष्ठं। माता। सूनवे। भागं। आ। अधात्। अनु।
अस्य। केतं। इषितं। सवित्रा॥ २॥ संऽआववर्ति। विऽस्थितः। जिगीषुः। विश्वेषां। कामः। चरतां। अमा।
अभूत्। शश्वान्। अपः। विऽकृतं। हित्वी। आ। अगात्। अनु। व्रतं। सवितुः। दैव्यस्य। त्वया। हितं। अप्यं।
अप्ऽसु। भागं। धन्व। अनु। आ। मृगयसः। वि। तस्थुः। वनानि। विऽभ्यः। नकिः। अस्य। तानि। व्रता।
देवस्य। सवितुः। मिनंति। यात्ऽराध्यं। वरुणः। योनिं। अप्यं। अनिऽशितं। निऽमिषि। जर्भुराणः।
विश्वः। मार्तंडः। व्रजं। आ। पशुः। गात्। स्थऽशः। जन्मानि। सविता। वि। आ। अकरित्यकः। न। यस्य। ३०७

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रः। वरुणः। न। मित्रः। व्रतं। अर्यमा। न। मिनंति। रुद्रः। न। अरातयः। तं। इदं। स्वस्ति। हुवे। देवं। सवितारं।
नमःऽभिः। भगं। धियं। वाजयंतः। पुरंऽधिं। नराशंसः। ग्नाःपतिः। नः। अव्याः। आऽअये। वामस्य। सं
ऽगथे। रयीणां। प्रियाः। देवस्य। सवितुः। स्याम। अस्मभ्यं। तत्। दिवः। अत्ऽभ्यः। पृथिव्याः। त्वया। दत्तं।
काम्यं। राधः। आ। गात्। शं। यत्। स्तोतृऽभ्यः। आपये। भवाति। उरुऽशंसाय। सवितः। जरित्रे॥३॥
ग्रावाणाऽइव। तत्। इत्। अर्थं। जरेथे इति। गृध्राऽइव। वृक्षं। निधिऽमंतं। अच्छ। ब्रह्माणाऽइव। विद
थे। उक्थऽशासा। दूताऽइव। हव्या। जन्या। पुरुऽत्रा। प्रातःऽयावाना। रथ्याऽइव। वीरा। अजाऽइ
व। यमा। वरं। आ। सचेथे इति। मेने इवेति मेनेऽइव। तन्वा। शुंभमाने इति। दंपती इवेति दंपतीऽइ

© Dharmartha Trust J&K. Digitized by eGangotri

१॰द्वि॰ वा। क्रतुऽविदा। जनेषु। शृंगा ऽइव। नः। प्रथमा। गंतं। अर्वाक्। शफौ ऽइव। जर्भुराणा। तरःऽभिः। चक्र
१०८ वाका ऽइव। प्रति। वस्तोः। उस्रा। अर्वांचा। यातं। रथ्या ऽइव। शक्रा। नावा ऽइव। नः। पारयतं। युगा ऽइ
108 व। नभ्या ऽइव। नः। उपधी ऽइवेत्युपऽधी ऽइव। प्रधी ऽइवेति प्रऽधी ऽइव। श्वाना ऽइव। नः। अरिषण्यो। तनू
नां। खृगला ऽइव। विऽस्रसः। पातं। अस्मान्। वाता ऽइव। अजुर्या। नद्या ऽइव। रीतिः। अक्षी ऽइवेत्य
क्षी ऽइव। चक्षुषा। आ। यातं। अर्वाक्। हस्तौ ऽइव। तन्वे। शंऽभविष्ठा। पादा ऽइव। नः। नयतं। वस्यः।
अच्छ। ५॥ ओष्ठौ ऽइव। मधु। आस्ने। वदंता। स्तनौ ऽइव। पिप्यतं। जीवसे। नः। नासा ऽइव। नः। त
न्वः। रक्षितारा। कर्णौ ऽइव। सुऽश्रुता। भूतं। अस्मे इति। हस्ता ऽइव। शक्तिं। अभि। संददी इति संऽ १०८

© Dharmartha Trust J&K. Digitized by eGangotri

ददी। नः। क्षामऽइव। नः। सं। अजतं। रजांसि। इमाः। गिरः। अश्विना। युष्मऽयंतीः। क्ष्णोत्रेणऽइव। स्वऽधि-
तिं। सं। शिशीतं। ववर्धनानि। ब्रह्म। स्तोमं। गृत्सऽमदासः। अक्रन्। तानि। नरा। जुजुषाणा। उप। या-
तं। ०। ५। सोमापूषणा। जनना। रयीणां। जनना। दिवः। जनना। पृथिव्याः। जातौ। विश्वस्य। भुव-
नस्य। गोपौ। देवाः। अकृण्वन्। अमृतस्य। नाभिं। इमौ। देवौ। जायमानौ। जुषंत। इमौ। तमांसि।
गूहतां। अजुष्टा। आभ्यां। इंद्रः। पक्वं। आमासु। अंतः। इति। सोमापूषऽभ्यां। जनत्। उस्रियासु।
सोमापूषणा। रजसः। विऽमानं। सप्तऽचक्रं। रथं। अविश्वऽमिन्वं। विषुऽवृतं। मनसा। युज्यमानं।
तं। जिन्वथः। वृषणा। पंचऽरश्मिं। दिवि। अन्यः। सदनं। चक्रे। उच्चा। पृथिव्यां। अन्यः। अधि। अं-

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ तरिक्षे। नौ। अस्मभ्यं। पुरुऽवारं। पुरुऽक्षुं। रायः। पोषं। वि। स्यतां। नाभिं। अस्मे इति। विश्वानि। अन्यः।
३०९ भुवना। जजान। विश्वं। अन्यः। अभिऽचक्षाणः। एति। सोमापूषणौ। अवतं। धियं। मे। युवाभ्यां। वि
109 श्वाः। पृतनाः। जयेम। धियं। पूषा। जिन्वतु। विश्वंऽइन्वः। रयिं। सोमः। रयिऽपतिः। दधातु। अवतु। देवी। अ
दितिः। अनर्वा। ०। द्वा। वायो इति। ये। ते। सहस्रिणः। रथासः। नेभिः। आ। गहि। निऽयुत्वान्। सोमऽपीतये।
निऽयुत्वान्। वायो इति। आ। गहि। अयं। शुक्रः। अयामि। ते। गंता। असि। सुन्वतः। गृहं। शुक्रस्य। अद्य।
गोऽआशिरः। इंद्रवायू इति। निऽयुत्वतः। आ। यातं। पिबतं। नरा। अयं। वां। मित्रावरुणा। सुतः। सोमः।
ऋतऽवृधा। मम। इत्। इह। श्रुतं। हवं। राजानौ। अनभिऽद्रुहा। ध्रुवे। सदसि। उत्ऽतमे। सहस्रऽस्थूणे। ३०९

© Dharmartha Trust J&K. Digitized by eGangotri

आ।सा।मे इति॥ ७।०।स चैत इति।अनेव ऽ क्रूरं।गोऽमत्।ऊं इति।सु।ना।स।त्सा।अश्वं ऽ वत्।या।तं।अश्वि
ना।वर्त्तिः।रुद्रा।नऽ पाय्यं।ना।यत्।पर।ना।अं तरः।आऽद् धर्ष्वत्।वृषण्व सू इति वृषण् ऽ वसू।दुः शं
सः।मर्त्यः।रिपुः।ना।नः।आ।वो वहं।अश्विना।रयिं।पिशं गऽ संदृशं।धिष्ण्या।वरिवः ऽ विदं।इंद्रः।
अंग।महत्।भयं।अभि।सत्।अप।चुच्यवत्।सः।हि।स्थिरः।विऽचर्षणिः।८।इंद्रः।च।मृळयाति।
नः।न।नः।पश्चात्।अघं।नशत्।भद्रं।भवाति।नः।पुरः।इंद्रः।आशाभ्यः।परि।सर्वाभ्यः।अभयं।करत्।
जेता।शत्रून्।विऽचर्षणिः।विश्वे देवासः।आ।गत।शृणुत।मे।इमं।हवं।आ।इदं।बर्हिः।नि।सीदत।ती
व्रः।वः।मधुऽमान्।अयं।शुनः होत्रेषु।मत्सरः।एतं।पिबत।काम्यं।११।१।अंबिऽतमे।नदीऽतमे।दे

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ विऽतमे। सरस्वति। अप्रशस्ताःऽइव। स्मसि। प्रऽशस्तिं। अंब। नः। कृधि। त्वेइति। विश्वा। सरस्वति। श्रि
३३० ता। आयूंषि। देव्यां। शुनःऽहोत्रेषु। मत्स्व। प्रऽजां। देवि। दिदिड्ढि। नः। इमा। ब्रह्म। सरस्वति। जुषस्व। वा
जिनीऽवति। या। ते। मन्म। गृत्सऽमदाः। ऋतऽवरि। प्रिया। देवेषु। जुह्वति। प्र। इतां। यज्ञस्य। शंऽभु
110 वा। युवां। इत्। आ। वृणीमहे। अग्निं। च। हव्यऽवाहनं। द्यावा। नः। पृथिवीइति। इमं। सिध्रं। अद्य।
दिविऽस्पृशं। यज्ञं। देवेषु। यच्छतां। आ। वां। उपऽस्थं। अद्रुहा। देवाः। सीदंतु। यज्ञियाः। इह। अद्य।
सोमऽपीतये॥ ३०॥ कनिक्रदत्। जनुषं। प्रऽब्रुवाणः। इयर्ति। वाचं। अरिताऽइव। नावं। सुऽमं
गलः। च। शकुने। भवासि। मा। त्वा। का। चित्। अभिऽभा। विश्व्या। विदत्। मा। त्वा। श्येनः। उत्। ३३०

© Dharmartha Trust J&K. Digitized by eGangotri

वधीत्। मा। सुऽपर्णः। मा। त्वा। विदत्। इषुऽमान्। वीरः। अस्ता। पित्र्यां। अनु। प्रऽदिशं। कनिक्रदत्। सुऽ
मंगलः। भद्रऽवादी। वद। इह। अव। क्रंद। दक्षिणतः। गृहाणां। सुऽमंगलः। भद्रऽवादी। शकुंते। मा। नः। स्ते
णि नः। ईशत। मा। अघऽशंसः। ०। ३३। प्रऽदक्षिणित्। अभि। गृणंति। कारवः। वयः। वदंतः। ऋतुऽथा। शकुंत
यः। उभे इति। वाचौ। वदति। सामगाःऽइव। गायत्रं। च। त्रैस्तुभं। च। अनु। राजति। उद्गाताऽइव। शकुने।
साम। गायसि। ब्रह्मपुत्रःऽइव। सवनेषु। शंससि। वृषाऽइव। वाजी। शिशुऽमतीः। अपिऽइत्य। सर्व
तः। नः। शकुने। भद्रं। आ। वद। विश्वतः। नः। शकुने। पुण्यं। आ। वद। आऽवदन्। त्वं। शकुने। भद्रं। आ। व
द। तूष्णीं। आसीनः। सुऽमतिं। चिकिद्धि। नः। यत्। उत्ऽपतन्। वदसि। कर्करिः। यथा। ०। ३। २। इति द्विती

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ यंमंऽलं॥ ॐ॥ सोमस्य।मा।तवसं।वक्षि।अग्ने।वन्हिं।चकर्थ।विदथे।यजध्यै।देवान्।अछ।दिद्यत्।
३३३ युंजे।अद्रिं।शंऽआयो।अग्ने।तन्वं।जुषस्व।प्रां।चं।यज्ञं।चकृम।वर्धतां।गीः।समित्ऽभिः।अग्निं।न
मसा।दुवस्यन्।दिवः।शशासुः।विदथा।कवीनां।गृत्साय।चित्।तवसे।गातुं।ईषुः।मयः।दधे।मे
धिरः।पूतऽदक्षः।दिवः।सुऽबंधुः।जनुषा।पृथिव्याः।अविंदन्।ऊं इति।दर्शतं।अप्ऽसु।अंतः।देवासः
।अग्निं।अपसि।स्वसॄणां।अवर्धयन्।सुऽभगं।सप्त।यन्हीः।श्वेतं।जज्ञानं।अरुषं।महित्वा।शि
शुं।न।जातं।अभि।आरुः।अश्वाः।देवासः।अग्निं।जनिमन्।वपुष्यन्।शुक्रेभिः।अंगैः।रजः।आऽत
तन्वान्।क्रतुं।पुनानः।कविऽभिः।पवित्रैः।शोचिः।वसानः।परि।आयुः।अपां।श्रियः।मिमीते।बृह ३३३

© Dharmartha Trust J&K. Digitized by eGangotri

तीः। अनूनाः॥ ६॥ ववाजा। सीं। अनदतीः। अदब्धाः। दिवः। यह्वीः। अवसानाः। अनग्नाः। सनाः। अत्र। यु
वतयः। सऽयोनीः। एकं। गर्भं। दधिरे। सप्त। वाणीः। स्तीर्णाः। अस्य। संऽहतः। विश्वऽरूपाः। घृतस्य। योनौ।
स्रवथे। मधूनां। अस्थुः। अत्र। धेनवः। पिन्वमानाः। मही इति। दस्मस्य। मातरा। समीची इति संऽईची।
बभ्राणः। सूनो इति। सहसः। वि। अद्यौत्। दधानः। शुक्रा। रभसा। वपूंषि। श्चोतंति। धाराः। मधुनः। घृ
तस्य। वृषा। यत्र। ववृधे। काव्येन। पितुः। चित्। ऊधः। जनुषा। विवेद। वि। अस्य। धाराः। असृजत्। वि।
धेनाः। गुहा। चरंतं। सखिऽभिः। शिवेभिः। दिवः। यह्वीभिः। न। गुहा। बभूव। पितुः। च। गर्भं। जनितुः। च।
बभ्रे। पूर्वीः। एकः। अधयत्। पीप्यानाः। वृष्णे। सपत्नी इति सऽपत्नी। शुचये। सबंधू इति सऽबंधू। उभे

© Dharmartha Trust J&K. Digitized by eGangotri

प·द्वि·
३३२
112

इति। अस्मै। मनुष्येइइति। नि। पाहि। १४। उरौ। महान्। अनिऽबाधे। ववृधे। आपः। अग्निं। यशसः। सं। हि।
पूर्वीः। ऋतस्य। योनौ। अशयत्। दमूनाः। जामीनां। अग्निः। अपसि। स्वसॄणां। अक्रः। न। बभ्रिः। संऽइथे।
महीनां। दिदृक्षेयः। सूनवे। भाःऽऋजीकः। उत्। उस्रियाः। जनिता। यः। जजान। अपां। गर्भः। नृऽतमः। यह्वः।
अग्निः। अपां। गर्भं। दर्शतं। ओषधीनां। वना। जजान। सुऽभगा। विऽरूपं। देवासः। चित्। मनसा। सं। हि।
जग्मुः। पनिष्ठं। जातं। तवसं। दुवस्यन्। बृहंतः। इत्। भानवः। भाःऽऋजीकं। अग्निं। सचंत। विद्युतः। न।
शुक्राः। गुहाःऽइव। वृद्धं। सदसि। स्वे। अंतः। अपारे। ऊर्वे। अमृतं। दुहानाः। ईळे। च। त्वा। यजमानः। हविःऽ
भिः। ईळे। सखिऽत्वं। सुऽमतिं। निऽकामः। देवैः। अवः। मिमीहि। सं। जरित्रे। रक्ष। च। नः। दम्येभिः। अनी ३३२

© Dharmartha Trust J&K. Digitized by eGangotri

केः। ३५। उपऽक्षेतारः। तव। सुऽप्रनीते। अग्ने। विश्वानि। धन्या। दधानाः। सुऽरेतसा। श्रवसा। तुंजमानाः।
अभि। स्याम। पृतनाऽयून्। अदेवान्। आ। देवानां। अभवः। केतुः। अग्ने। मंद्रः। विश्वानि। काव्यानि। विद्वा
न्। प्रति। मर्तान्। अवासयः। दमूनाः। अनु। देवान्। रथिरः। यासि। साधन्। नि। दुरोणे। अमृतः। मर्त्या
नां। राजा। ससाद। विदथानि। साधन्। घृतऽप्रतीकः। उर्विया। वि। अद्यौत्। अग्निः। विश्वानि। काव्या
नि। विद्वान्। आ। नः। गहि। सख्येभिः। शिवेभिः। महान्। महीभिः। ऊतिऽभिः। सरण्यन्। अस्मे इति।
रयिं। बहुलं। संऽतरुत्रं। सुऽवाचं। भागं। यशसं। कृधि। नः। एता। ते। अग्ने। जनिम। सनानि। प्र। पू
र्व्याय। नूतनानि। वोचं। महान्ति। वृष्णे। सवना। कृता। इमा। जन्मन्ऽजन्मन्। निऽहितः। जातऽवेदाः। १०। हि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ऋ॰ विश्वामित्रेभिः। इध्यते। अजस्रः। तस्य। वयं। सुऽमतौ। यज्ञियस्य। अपि। भद्रे। सौमनसे। स्याम। आ। इमं। य
३३२ ज्ञं। सहसाऽवन्। त्वं। नः। देवऽत्रा। धेहि। सुक्रतो इति सुऽक्रतो। रराणः। प्र। यंसि। होतः। बृहतीः। इषः। नः। अ
113 ग्ने। महि। द्रविणं। आ। यजस्व। इळां। अग्ने। पुरुऽदंसं। सनिं। गोः। शश्वत्ऽतमं। हवमानाय। साध। स्या
त्। नः। सूनुः। तनयः। विजाऽवा। अग्ने। सा। ते। सुऽमतिः। भूतु। अस्मे इति। ३६। वैश्वानराय। धिषणां।
ऋतऽवृधे। घृतं। न। पूतं। अग्नये। जनामसि। द्विता। होतारं। मनुषः। च। वाघतः। धिया। रथं। न। कुलि
शः। सं। ऋण्वति। सः। रोचयत्। जनुषा। रोदसी इति। उभे इति। सः। मात्रोः। अभवत्। पुत्रः। ईड्यः। हव्य
ऽवाट्। अग्निः। अजरः। चनःऽहितः। दुःऽदभः। विशां। अतिथिः। विभाऽवसुः। क्रत्वा। दक्षस्य। तरुषः। ३३२

© Dharmartha Trust J&K. Digitized by eGangotri

विऽधर्मणि। देवासः। अग्निं। जनयंत। चित्तिऽभिः। रुरुचानं। भानुना। ज्योतिषा। महां। अत्यं। न। वाजं। सनि
ष्यन्। उप। ब्रुवे। आ। मंद्रस्य। सनिष्यंतः। वृणीमहे। वरेण्यं। अह्रयं। वाजं। ऋग्मियं। रातिं। भृगूणां। उशि
जं। कविऽक्रतुं। अग्निं। राजंतं। दिव्येन। शोचिषा। अग्निं। सुम्नाय। दधिरे। पुरः। जनाः। वाजऽश्रवसं।
इह। वृक्तऽबर्हिषः। यतऽस्रुचः। सुऽरुचं। विश्वऽदेव्यं। रुद्रं। यज्ञानां। साधत्ऽइष्टिं। अपसां। ॥५॥ पाव
कऽशोचेः। तव। हि। क्षयं। परि। होतः। यज्ञेषु। वृक्तऽबर्हिषः। नरः। अग्ने। दुवः। इच्छमानाः। आप्यं। उ
प। आसते। द्रविणं। धेहि। तेभ्यः। आ। रोदसी इति। अपृणत्। आ। स्वः। महत्। जातं। यत्। एनं। अप
सः। अधारयन्। सः। अध्वराय। परि। नीयते। कविः। अत्यः। न। वाजऽसातये। चनःऽहितः। नमस्य

© Dharmartha Trust J&K. Digitized by eGangotri

प·छि·

११४

त। हव्यऽदातिं। सुऽअध्वरं। दुवस्यन। दम्यं। जातऽवेदसं। रथीः। ऋतस्य। बृहतः। विऽचर्षणिः। अग्निः। दे
वानां। अभवत्। पुरःऽहितः। तिस्रः। यह्वस्य। संऽइधः। परिऽज्मनः। अग्नेः। अपुनन्। उशिजः। अमृतस्य
वः। तासां। एकां। अदधुः। मर्त्ये। भुजं। ऊं इति। लोकं। ऊं इति। द्वे इति। उप। जामिं। ईयतुः। विशं। कविं। वि
श्पतिं। मानुषीः। इषः। सं। सीं। अकृण्वन्। स्वऽधितिं। न। तेजसा। सः। उत्ऽवतः। निऽवतः। याति। वेवि
षत्। सः। गर्भं। एषु। भुवनेषु। दीधरत्॥१०॥ सः। जिन्वते। जठरेषु। प्रऽजज्ञिऽवान्। वृषा। चित्रेषु। नानद
त्। न। सिंहः। वैश्वानरः। पृथुऽपाजाः। अमर्त्यः। वसु। रत्ना। दयमानः। वि। दाशुषे। वैश्वानरः। प्रत्नऽथा।
नाकं। आ। अरुहत्। दिवः। पृष्ठं। भंदमानः। सुमन्मऽभिः। सः। पूर्वऽवत्। जनयन्। जंतवे। धनं। समानं। ११४

© Dharmartha Trust J&K. Digitized by eGangotri

अज्मं।परि।एति।आ।अग्रे।विशः।कृतऽवानं।यज्ञियं।विप्रं।उक्थ्यं।आ।यं।दधे।मातरिश्वा।दिवि।क्षयं।तं।
चित्रऽयामं।हरिऽकेशं।ईमहे।सुऽदीतिं।अग्निं।सुविताय।नव्यसे।शुचिं।न।यामन्।इषिरं।स्वःऽदृ
शं।केतुं।दिवः।रोचनऽस्थां।उषःऽबुधं।अग्निं।मूर्धानं।दिवः।अप्रतिऽस्कुतं।तं।ईमहे।नमसा।वा
जिनं।बृहत्।मन्द्रं।होतारं।शुचिं।अद्वयाविनं।दमूनसं।उक्थ्यं।विश्वऽचर्षणिं।रथं।न।चित्रं।वपु
षाय।दर्शतं।मनुःऽहितं।सदा।इत्।रायः।ईमहे॥१५॥वैश्वानराय।पृथुऽपाजसे।विपः।रत्ना।विधं
त।धरुणेषु।गातवे।अग्निः।हि।देवान्।अमृतः।दुवस्यति।अथ।धर्माणि।सनता।न।दूदुषत्।अं
तः।दूतः।रोदसी इति।दस्मः।ईयते।होता।निऽसत्तः।मनुषः।पुरःऽहितः।क्षयं।बृहन्तं।परि।भूषति।द्यु॰

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ६ि भिः। देवेभिः। अग्निः। इषितः। धिया। वसु। केतुं। यज्ञानां। विदथस्य। साधनं। विप्रासः। अग्निं। महयं
११५ न। चित्तिऽभिः। अपांसि। यस्मिन्। अधि। संऽदधुः। गिरः। तस्मिन्। सुम्नानि। यजमानः। आ। चके।
पिता। यज्ञानां। असुरः। विपःऽचितां। विऽमानं। अग्निः। वयुनं। च। वाघतां। आ। विवेश। रोदसी इति।
भूरिऽवर्पसा। पुरुऽप्रियः। मंदते। धामऽभिः। कविः। चंद्रं। अग्निं। चंद्रऽरथं। हरिऽव्रतं। वैश्वानरं। अ
प्सुऽसदं। स्वःऽविदं। विऽगाहं। तूर्णिं। तविषीभिः। आऽवृतं। भूर्णिं। देवासः। इह। सुऽश्रियं। दधुः। ॥२॥
अग्निः। देवेभिः। मनुषः। च। जंतुऽभिः। तन्वानः। यज्ञं। पुरुऽपेशसं। धिया। रथीः। अंतः। ईयते। सा
धदिष्टिऽभिः। जीरः। दमूनाः। अभिशस्तिऽचातनः। अग्ने। जरस्व। सुऽअपत्ये। आयुनि। ऊर्जा। पि ११५

© Dharmartha Trust J&K. Digitized by eGangotri

वस्व । सः । इषः । दीदिहि । नः । वयांसि । जिह्वा । बृहतः । च । जागृवे । उशिक् । देवानां । असि । सुऽक्रतुः । विपां । वि
श्पतिं । यह्वं । अतिथिं । नरः । सदा । यंतारं । धीनां । उशिजं । च । वाघतां । अध्वराणां । चेतनं । जातऽवेदसं ।
प्र । शंसंति । नमसा । जूतिऽभिः । वृधे । विभाऽवा । देवः । सुऽरणः । परि । क्षितीः । अग्निः । बभूव । शवसा ।
सुमत्ऽरथः । तस्य । व्रतानि । भूरिऽपोषणः । वयं । उप । भूषेम । दमे । आ । सुवृक्तिऽभिः । वैश्वानर । तव ।
धामानि । आ । चके । येभिः । स्वःऽवित् । अभवः । विऽचक्षण । जातः । आ । अपृणः । भुवनानि । रोदसी इ
ति । अग्ने । ता । विश्वा । परिऽभूः । असि । त्मना । वैश्वानरस्य । दंसनाभ्यः । बृहत् । अरिणात् । एकः । सु
ऽअपस्यया । कविः । उभा । पितरा । महयन् । अजायत । अग्निः । द्यावापृथिवी इति । भूरिऽरेतसा ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ दि॰ ॥२३॥ समित्ऽसमित् । सुऽमनाः । बोधि । अस्मे इति । शुचाऽशुचा । सुऽमतिं । रासि । वस्वः । आ । देव । देवान् ।

३१६ यजथाय । वक्षि । सखा । सखीन् । सुऽमनाः । यक्षि । अग्ने । यं । देवासः । त्रिः । अहन् । आऽयजंते । दिवेऽदि

वे । वरुणः । मित्रः । अग्निः । सः । इमं । यज्ञं । मधुऽमंतं । कृधि । नः । तनूऽनपात् । घृतऽयोनिं । विधंतं । प्र । दीधि

116 तिः । विश्वऽवारा । जिगाति । होतारं । इळः । प्रथमं । यजध्यै । अछा । नमःऽभिः । वृषभं । वंदध्यै । सः । देवान् ।

यक्षत् । इषितः । यजीयान् । ऊर्ध्वः । वां । गातुः । अध्वरे । अकारि । ऊर्ध्वा । शोचींषि । प्रऽस्थिता ।

रजांसि । दिवः । वा । नाभा । नि । असादि । होता । स्तृणीमहि । देवऽव्यचाः । वि । बर्हिः । सप्त । होत्राणि । मन

सा । वृणानाः । इन्वंतः । विश्वं । प्रति । यन् । ऋतेन । नृऽपेशसः । विदथेषु । प्र । जाताः । अभि । इमं । यज्ञं । वि ३१६

© Dharmartha Trust J&K. Digitized by eGangotri

चरंत। पूर्वीः। ररा। आ। भंदमाने इति। उषसौ। उपाके इति। उत। स्मये इति। तन्वा। विरूपे इति। विऽरूपे।
यथा। नः। मित्रः। वरुणः। जुजोषत्। इंद्रः। मरुत्वान्। उत। वा। महःऽभिः। दैव्या। होतारा। प्रथमा। नि।
ऋंजे। सप्त। पृक्षासः। स्वधया। मदंति। ऋतं। शंसंतः। ऋतं। इत्था। ते। आहुः। अनु। व्रतं। व्रतऽपाः। दीध्या
नाः। आ। भारती। भारतीभिः। सऽजोषाः। इळा। देवैः। मनुष्येभिः। अग्निः। सरस्वती। सारस्वतेभिः।
। अर्वाक्। नि। स्थः। देवीः। बर्हिः। आ। इदं। सदंतु। तत्। नः। तुरीपं। अध। पोषयित्नु। देव। त्वष्टः। वि। ररा
णः। स्यस्व। इति। स्यस्व। यतः। वीरः। कर्मण्यः। सुऽदक्षः। युक्तऽग्रावा। जायते। देवऽकामः। वनस्पते। अ
व। सृज। उप। देवान्। अग्निः। हविः। शमिता। सूदयाति। सः। इत्। ऊं इति। होता। सत्यऽतरः। यजा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ द्वि॰ तिा यथा। देवानां। जनिमानि। वेद। आ। याहि। अग्ने। सम्ऽइधानः। अर्वाङ्। इंद्रेण। देवैः। सऽरथं। तुरेभिः।
११८ बर्हिः। नः। आस्तां। अदितिः। सुऽपुत्रा। स्वाहा। देवाः। अमृताः। मादयंतां॥ २३॥ प्रति। अग्निः। उषसः। चे
किताना। अबोधि। विप्रः। पदऽवीः। कवीनां। पृथुऽपाजाः। देवयत्ऽभिः। सम्ऽइद्धः। अप। द्वारा। तमसः। व
117 ह्निः। आव रिसा। वः। प्र। इत्। ऊं इति। अग्निः। ववृधे। स्तोमेभिः। गीःऽभिः। स्तोतॄणां। नमस्यः। उक्थैः। पू
र्वीः। ऋतस्य। सम्ऽदृशः। चकानः। सं। दूतः। अद्यौत्। उषसः। विऽरोके। अधायि। अग्निः। मानुषीषु। वि
क्षु। अपां। गर्भः। मित्रः। ऋतेन। साधन्। आ। हर्यतः। यजतः। सानु। अस्थात्। अभूत्। ऊं इति। विप्रः।
हव्यः। मतीनां। मित्रः। अग्निः। भवति। यत्। सम्ऽइद्धः। मित्रः। होता। [illegible]। वरुणः। जातऽवेदाः। मित्रः। ११८

© Dharmartha Trust J&K. Digitized by eGangotri

अध्वर्युः। इषिरः। दमूनाः। मित्रः। सिंधूनां। उत। पर्वतानां। पाति। प्रियं। रिपः। अग्रं। पदं। वेः। पाति। यह्वः।
चरणं। सूर्यस्य। पाति। नाभा। सप्तऽशीर्षाणं। अग्निः। पाति। देवानां। उपऽमादं। ऋष्वः। २४। ऋभुः।
चक्रे। ईड्यं। चारु। नाम। विश्वानि। देवः। वयुनानि। विद्वान्। ससस्य। चर्म। घृतऽवत्। पदं। वेः। तत्। इ
त्। अग्निः। रक्षति। अप्रऽयुच्छन्। आ। योनिं। अग्निः। घृतऽवंतं। अस्थात्। पृथुऽप्रगानं। उशंतं। उशानः।
दीद्यानः। शुचिः। ऋष्वः। पावकः। पुनःऽपुनः। मातरा। नव्यसी इति। करिति कः। सद्यः। जातः। ओषधी
भिः। ववक्षे। यदि। वर्धंति। प्रऽस्वः। घृतेन। आपःऽइव। प्रऽवता। शुंभमानाः। उरुष्यत्। अग्निः। पित्रोः। उ
पऽस्थे। उत्। ऊं इति। स्तुतः। संऽइधा। यह्वः। अद्यौत्। वर्ष्मन्। दिवः। अधि। नाभा। पृथिव्याः। मित्रः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰दि॰ ३३८ 118

ग्निः। ईड्यः। मातरिश्वा। आ। दूतः। वक्षत्। यजथाय। देवान्। उत्। अस्तंभीत्। संऽइधा। नाकं। ऋष्वः। अग्निः।
भवन्। उत्ऽतमः। रोचनानां। यदि। भृगुऽभ्यः। परि। मातरिश्वा। गुहा। संतं। हव्यऽवाहं। संऽईधे।०।२५।
प्र। कारवः। मननाऽवच्यमानाः। देवद्रीचीं। नयत। देवऽयंतः। दक्षिणाऽवाट्। वाजिनी। प्राची। एति। हविः।
भरंती। अग्नये। घृताची। आ। रोदसीइति। अपृणाः। जायमानः। उत। प्र। रिक्थाः। अध। नु। प्रयज्योइ
तिप्रऽयज्यो। दिवः। चित्। अग्ने। महिना। पृथिव्याः। वच्यंतां। ते। वह्नयः। सप्तऽजिह्वाः। द्यौः। च। त्वा। पृथि
वी। यज्ञियासः। नि। होतारं। सादयंते। दमाय। यदि। विशः। मानुषीः। देवऽयंतीः। प्रयस्वतीः। ईळते। शु
क्रं। अर्चिः। महान्। सधऽस्थे। ध्रुवः। आ। निऽसत्तः। अंतः। द्यावा। माहिनेइति। हर्यमाणः। आस्केइति। ३३८

सपत्नीइति सऽपत्नी। अजरेइति। अमृक्तेइति। सबर्दुघेइति सबःऽदुघे। उरुऽगायस्य। धेनूइति। व्रता। ते।
अग्ने। महतः। महानि। तव। क्रत्वा। रोदसीइति। आ। ततंथ। त्वं। दूतः। अभवः। जायमानः। त्वं। नेता। वृषभ।
चर्षणीनां॥ २॥ ऋतस्य। वा। केशिना। योग्याभिः। घृतऽस्नुवा। रोहिता। धुरि। धिष्व। अथ। आ। वह।
देवान्। देव। विश्वान्। सुऽअध्वरा। कृणुहि। जातऽवेदः। दिवः। चित्। आ। ते। रुचयंत। रोकाः। उषः। विऽभा
तीः। अनु। भासि। पूर्वीः। अपः। यत्। अग्ने। उशधक्। वनेषु। होतुः। मंद्रस्य। पनयंत। देवाः॥ ४॥ वा। ये।
अंतरिक्षे। मदंति। दिवः। वा। ये। रोचने। संति। देवाः। ऊमाः। वा। ये। सुऽहवासः। यजत्राः। आऽयेमिरे।
रथ्यः। [illegible]। अग्ने। अश्वाः॥ ५॥ सऽरथं। याहि। अर्वाङ्। नाना। रथं। वा। विऽभवः। हि। अश्वाः। पत्नीःऽव

© Dharmartha Trust J&K. Digitized by eGangotri

प॰द्वि॰ ततः।त्रिंशतौ।त्रीन्।चा।देवान्।अनुऽस्वधं।आ।वह।मादयस्व।सः।होता।यस्य।रोदसी इति।चित्।उर्वी इ

३३९ ति।यज्ञंऽयज्ञं।अभि।वृधे।गृणीतः।प्राची इति।अध्वराऽइव।न स्तुतः।सुमेके इति सुऽमेके।ऋतवरी इ

त्यृतऽवरी।ऋतऽजातस्य।सत्ये इति।६।काम अग्ने।।१।।स्याम्नः स्तुतः।।१।।२।।इति द्वितीयाष्टके अष्टमो

ध्यायः।।समाप्तः।।शुभं भवतु।।भग्नपृष्ठकटिग्रीवा स्तब्धदृष्टिरधोमुखं।।कष्टेन लिखितं ग्रंथं य

त्नेन परिपालयेत्।।विद्वज्जन हि जानाति विद्वज्जनपरिश्रमं।।न हि वंध्या प्रजानाति गुर्विप्रसूतवेद

ना।।यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया।।यदि शुद्धमशुद्धं वा मम दोषो न विद्यते।। ।। ।।

119

३३९

© Dharmartha Trust J&K. Digitized by eGangotri

पद्धि: संवत्॥१८८९॥शाके॥१७५४॥श्रीमननामसंवत्सरे॥उदगयनेवसंतर्तौ ज्येष्ठेमासेशुक्लपक्षेप्रप

३१२· यांतिथौसौम्यवासरे॥गुर्जरोपनामकरामचंद्रात्मजपुरुषोत्तमेनलिखितं॥ ७॥ ७॥ ॥

120

© Dharmartha Trust J&K. Digitized by eGangotri

[illegible]

पत्रे
१२०

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

प० चं० श्रीगणेशायनमः॥ हरिःॐ॥ आमग्नेगायत्र्यांस्यापंचम्योपंक्तीअग्नओजिष्ठमेस्या
१ चतुर्थीचजनन्स्यषट्सुलंभरोआगतंगागत्येयैलोगायत्रेसग्निंस्तोमेनसप्तवेधसे
पंचांगिरसोधरुणोबृहस्पूरुःपंक्त्यंतेत्थायज्ञैःप्रालमर्कवाह्नहितोभ्यवस्थावद्विर्गा
यत्र्यावनुष्टुभोविराड्रूपायमग्नेचतुष्केसप्तयस्वंतःपंक्त्यंतेमनुवस्ससःसविश्वसा
मविश्वसामाग्नेष्टुभोविश्वचर्षणिरग्नेत्वंगोपायनालौपायनावोबंधुःसुबंधुःश्रुत
बंधु र्विप्रबंधुश्चैकर्चाद्वैपदंमहीवोनवकस्सप्तवआनुष्टुभमग्नेगायत्रमंस्यावैश्वदेव्यन
स्वंतापट्ग्रेरक्षःपौरुकुत्स्योद्वौत्र्यरुणत्रसदस्यूराजानौभारतश्वाश्वमेधोस्या ३

© Dharmartha Trust J&K. Digitized by eGangotri

स्तिस्रो नुष्टुभो नाम मनेदध्यादिति सर्वो स्वस्त्रिं केचिदं सैंद्राग्नी समिद्धो विश्ववारा त्रे
वे यी [illegible] त्रिष्टुब्जगती त्रिष्टुबनुष्टुब्गायत्र्यो स्यर्यमा पंचो नागो रिवी लिः शास्त्यं ऐंद्रमु
शना यदोशनसो वा पादः कस्यव भ्रुर्मणं वयो प्य त्रराजा स्तुतं इंद्रो रथा यस मे नो ना व
स्तुरुग्रमिति कौत्स्यो शनसो वा पा दो पवैं द्रा कौत्स्य दर्दह्णी शगातुः ॥ २५॥ ॥ ॐ त्वं॥
त्वां । अग्ने । हविष्मंतः । देवं । मर्त्तासः । ईळते । मन्ये । त्वा । जातऽवेदसं । सः । हव्या । वक्षि । आ
नुषक् । अग्निः । होता । दास्वतः । क्षयस्य । प्रभोः । बर्हिषः । सं । यज्ञा । सः । चरंति । यं । सं । वा
जासः । श्रवस्यवः । उता । स्म । यो । शिश्वे । यथा । नवं । जनिष्ट । अरणी । इति । धन्योरं । मानुषीणां ।

प.वे. विशां।अग्निं।सुऽअध्वरं।उत।स्म।दुःऽगृभीयसे।पुत्रः।न।ह्वार्याणां।पुरु।यः।दग्धा।
२ असि।वना।अग्ने।पशुः।न।यवसे।अध।स्म।यस्य।अर्चयः।सम्यक्।संऽयन्ति।धूमि
नः।यत्।ईं।अह।त्रितः।दिवि।उप।ध्माताऽइव।धमति।शिशीते।ध्मातरि।यथा।तव।अ
हं।अग्ने।ऊतिऽभिः।मित्रस्य।च।प्रऽशस्तिऽभिः।द्वेषःऽयुतः।न।दुःऽइता।तुर्याम।मर्त्यानां।
तं।नः।अग्ने।अभि।नरः।रयिं।सहस्वः।आ।भर।सः।क्षेपयत्।सः।पोषयत्।भुवत्।
वाजस्य।सातये।उत।एधि।पृत्ऽसु।नः।वृधे॥१॥अग्ने।ओजिष्ठं।आ।भर।द्युम्नं।
2
अस्मभ्यं।अध्रिगो इत्यध्रिऽगो।प्र।नः।राया।परीणसा।रत्सि।वाजाय।पंथां।खं। २

© Dharmartha Trust J&K. Digitized by eGangotri

नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना । त्वे इति । असुर्यं । आ । अरुहत् । क्राणा ।
मित्रः । न । यज्ञियः ॥ ० ॥ एषां । गयं । पुष्टिं । च । वर्धय । ये । स्तोमेभिः । प्र । सूरयः । नरः ।
मघानि । आनशुः । ये । अग्ने । चंद्र । ते । गिरः । शुंभंति । अश्वऽराधसः । शुष्मेभिः ।
शुष्मिणः । नरः । दिवः । चित् । येषां । बृहत् । सुऽकीर्तिः । बोधति । त्मना ॥ ० ॥ भ्राजंतः ।
यंति । धृष्णुऽया । परिऽज्मानः । न । विऽद्युतः । स्वानः । रथः । न । वाजऽयुः । नु । नः ।
अग्ने । ऊतये । सऽबाधसः । च । रातये । अस्माकासः । च । सूरयः । विश्वाः । आ ।
आशाः । तरीषणि ॥ ० ॥ अंगिरः । स्तुतः । स्तवानः । आ । भर । होतः । विभ्वऽसहं । र

© Dharmartha Trust J&K. Digitized by eGangotri

१.वे. यिं। स्तोतृऽभ्यः। स्तवसे। च। नः॥ [illegible] ॥२॥ जनस्य। गोपाः। अजनिष्ट। जागृविः। अग्निः।
३ सुऽदक्षः। सुविताय। नव्यसे। घृतऽप्रतीकः। बृहता। दिविऽस्पृशा। द्युऽमत्। वि। भाति। भ
रतेभ्यः। शुचिः। यज्ञस्य। केतुं। प्रथमं। पुरःऽहितं। अग्निं। नरः। त्रिऽसधस्थे। सं। ईधिरे।
3 इन्द्रेण। देवैः। सऽरथं। सः। बर्हिषि। सीदत्। नि। होता। यजथाय। सुऽक्रतुः। असंऽमृष्टः। जा
यसे। मात्रोः। शुचिः। मन्द्रः। कविः। उत्। अतिष्ठः। विवस्वतः। घृतेन। त्वा। अवर्धयन्। अग्ने।
आऽहुत। धूमः। ते। केतुः। अभवत्। दिवि। श्रितः। अग्निः। नः। यज्ञं। उप। वेतु। साधुऽया।
अग्निं। नरः। वि। भरन्ते। गृहेऽगृहे। अग्निः। दूतः। अभवत्। हव्यऽवाहनः। अग्निं। वृणानाः। ३

© Dharmartha Trust J&K. Digitized by eGangotri

वृणते। कविऽक्रतुं। तुभ्य। इदं। अग्ने। मधुमत्ऽतमं। वचः। तुभ्यं। मनीषा। इयं। अस्तु। शं।
हृदे। त्वां। गिरः। सिंधुंऽइव। अवनीः। महीः। आ। पृणंति। शवसा। वर्धयंति। च। त्वां। अग्ने।
अंगिरसः। गुहा। हितं। अनु। अविंदन्। शिश्रियाणं। वनेऽवने। सः। जायसे। मथ्यमानः।
सहः। महत्। त्वां। आहुः। सहसः। पुत्रं। अंगिरः॥ ३॥ प्र। अग्नये। बृहते। यज्ञियाय। ऋत
स्य। वृष्णे। असुराय। मन्म। घृतं। न। यज्ञे। आस्ये। सुऽपूतं। गिरं। भरे। वृषभाय। प्रतीचीं।
ऋतं। चिकित्वः। ऋतं। इत्। चिकिद्धि। ऋतस्य। धाराः। अनु। तृंधि। पूर्वीः। न। अहं। यातुं।
सहसा। न। द्वयेन। ऋतं। सपामि। अरुषस्य। वृष्णः। कया। नः। अग्ने। ऋतयन्। ऋतेन।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प॰ भुवः। न वेदाः। पृथस्या। नव्यः। वेदा। मे। देवः। ऋलुःपाः। ऋतूनां। ना। अहं। पतिं। सनितुः।
४ अस्या। रायः। के। ते। अग्ने। रिपवे। बंधनासः। के। पायवः सनिषंत। द्युमंतः। के। धासिं। वं॰:१२
अग्ने। अनृतस्य। पांति। के। असतः। वचसः। संति। गोपाः। सखायः। ते। विषुणा। अ
ग्ने। एते। शिवासः। संतः। अशिवाः। अभूवन्। अधूर्षत। स्वयं। एते। वचोभिः। ऋजूयु
ते। वृजिनानि। ब्रुवंतः। यः। ते। अग्ने। नमसा। यज्ञं। ईट्टे। ऋतं। सः। पाति। अरुषस्य
वृष्णः। नस्य। क्षयः। पृथुः। आ। साधुः। एतु। प्रसर्स्राणस्य। नहुषस्य। शेषः। ५। अं
तः। वा। हृषा। महो। अर्चंतः। सं। इधीमहि। अग्ने। अर्चंतः। ऊतये। अग्नेः। स्तोमं। मनाम। ४

© Dharmartha Trust J&K. Digitized by eGangotri

महे। सिध्रं। अद्य। दिविऽस्पृशः। देवस्य। द्रविणस्यवः। अग्निः। जुषत। नः। गिरः।
होता। यः। मानुषेषु। आ। सः। यक्षत्। दैव्यं। जनं। त्वं। अग्ने। सऽप्रथाः। असि। जु
ष्टः। होता। वरेण्यः। त्वया। यज्ञं। वि। तन्वते। त्वां। अग्ने। वाजऽसातमं। विप्राः।
वर्धंति। सुऽस्तुतं। सः। नः। रास्व। सुऽवीर्यं। अग्ने। नेमिः। अरान्ऽइव। देवान्।
त्वं। परिऽभूः। असि। आ। राधः। चित्रं। ऋंजसे। ॥५॥ अग्निं। स्तोमेन। बोधय।
संऽइधानः। अमर्त्यं। हव्या। देवेषु। नः। दधत्। तं। अध्वरेषु। ईळते। देवं। मर्ताः।
अमर्त्यं। यजिष्ठं। मानुषे। जने। तं। हि। शश्वंतः। ईळते। स्रुचा। देवं। घृतऽश्चु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ वे॰ ते। अग्निं। हव्याय। वोळ्हवे। अग्निः। जातः। अरोचत। घ्नन्। दस्यून्। ज्योतिषा। तमः। अवि
५ दत्। गाः। अपः। स्वः। इति स्वः। अग्निं। ईळेन्यं। कविं। घृतऽपृष्ठं। सपर्यत। वेतु। मे। शृणवत्
हवं। अग्निं। घृतेन। ववृधुः। स्तोमेभिः। विश्वऽचर्षणिं। सुऽआधीभिः। वचस्युऽभिः। ६॥
प्र। वेधसे। कवये। वेद्याय। गिरं। भरे। यशसे। पूर्व्याय। घृतऽप्रसत्तः। असुरः। सुऽशेवः।
रायः। धर्ता। धरुणः। वस्वः। अग्निः। ऋतेन। ऋतं। धरुणं। धारयन्त। यज्ञस्य। शाके। परमे। व्यो
मन्। दिवः। धर्मन्। धरुणे। सेदुषः। नॄन्। जातैः। अजातान्। अभि। ये। ननक्षुः। अं
हःऽयुवः। तन्वः। तन्वते। वि। वयः। महत्। दुस्तरं। पूर्व्याय। सः। संऽवतः। नवऽजातः। तुतुर्यात् ५

© Dharmartha Trust J&K. Digitized by eGangotri

ता।सिंहा।ना।क्रुद्धा।अभितः।परि।स्थुः।मातृा।ऽइवा।यत्।आ।भरसे।पप्रथा।नः।अग्नेऽअग्ने।धा
यसे।वृक्षसे।चु।वयः।ऽवयः।अरसे।यत्।दधानः।परि।त्मना।विषुरूपः।जिगासि।वा
जः।नु।ते।शवसः।पातु।अंते।उरु।दीर्घा।पुरूणि।देव।रायः।पदं।ना।नामः।गुहा।दधानः
।मुहः।रायः।चितयन्।अग्निं।अस्मारिष्यत्स्वः।।७।।बृहत्।वयः।हि।भानवे।अर्च।देवाय।
अग्नये।यं।मित्रं।न।प्रशस्तिभिः।मर्तासः।दधिरे।पुरः।सः।हि।द्युभिः।जनानां।हो
ता।दक्षस्य।बाह्वोः।वि।हव्यं।अग्निः।आनुषक्।भगः।न।वारं।ऋण्वति।अस्य।स्तो
मे।मघोनः।सख्ये।वृद्धशोचिषः।विश्वा।यस्मिन्।तुविस्वनि।सं।अर्यः।शुष्मं।आऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ ६

दधुः। अध। हि। अग्ने। एषां। सुऽवीर्यस्य। मंहना। तं। इत्। यह्वं। न। रोदसी इति। परि। श्र
वः। बभूवतुः। नु। नः। आ। इहि। वार्यं। अग्ने। गृणानः। आ। भर। ये। वयं। ये। च। सूर
यः। स्वस्ति। धामहे। सचा।०।। ८।। आ। यत्तैः। दिव। मर्तः। इत्था। तव्यांसं। कृतये। अ
ग्निं। कृते। सुऽअध्वरे। पुरुः। ईळीत। अवसे। अस्य। हि। स्वऽयशाः। तरः। आसा। विऽ
धर्मन्। मन्यसे। तं। नाकं। चित्रऽशोचिषं। मंद्रं। परः। मनीषया। अस्य। वै। अग्ने।
द्युऽइति। अर्चिषा। यः। अयुक्त। तुजा। गिरा। दिवः। न। यस्य। रेतसा। बृहत्। शोचंति।
अर्चयः। अस्य। क्रत्वा। विऽचेतसः। दस्मस्य। वसु। रथे। आ। अध। विश्वासु। ६

© Dharmartha Trust J&K. Digitized by eGangotri

हव्यः। अग्निः। विक्ष्वा। प्र। शस्यते। तु। नः। इत्। आहि। वार्यं। आ। सा। सवंता। सूरयः। ऊर्जः।
नपात्। अभिऽइष्टये। पाहि। शग्धि। स्वस्तये। ०॥१॥ गातुः। अग्निः। पुरुऽप्रियः। विशः।
स्तवेत। अतिथिः। विश्वानि। यः। अमर्त्यः। हव्या। मर्तेषु। रण्यति। द्विता। यः। सुक्रः।
वाहसे। स्वस्य। दक्षस्य। मंहना। इंदुं। सः। धत्ते। आनुऽषक्। स्तोता। चित्। ते। अमर्त्य।
तं। वः। दीर्घायुःऽशोचिषं। गिरा। हुवे। मघोनां। अरिष्टः। येषां। रथः। वि। अश्वऽदावन्।
वा॥ ईयते। विप्रो। यष्ठु। दीधितिः। आऽसन्नाः। वृक्ऽस्था। पांति। ये। स्तीर्णा। बर्हिः। स्वःऽनरे।
श्रवांसि। दधिरे। परि। यो। मे। पंचाशतं। ददुः। अश्वानां। सधऽस्तुति। द्युऽमत्। अग्ने।

© Dharmartha Trust J&K. Digitized by eGangotri

ऋ.प. महि। अर्वः। बृहता। रुधि। मघोनां। नृऽवत्। अमृत। नृणां॥ १४॥ अभि। अवऽस्थाः। ग्ना।
८ ना। ग्रंते। ग्ना। वव्रे। वव्रिः। चिकेत। उपऽस्थे। माता। नुः। वि। वृष्टे। अनु। रे। वि। ज्विन। यंतः। अनिऽ
मिषं। नृम्णा। पाति। आ। दृढ्हां। पुरं। विविशुः। आ। श्वैगे। यस्यां। अनु। वेः। घुऽमता। वर्धंता।
हृद्रः। निऽसक्। मनीवः। वृहतऽउक्थ्यः। एना। मध्वा। न। वाजऽयुः। प्रियं। दुग्धं। न। काम्यं।
अजामि। जाम्योः। सचा। घर्मः। न। वाजऽजठरः। अदब्धः। शश्वतः। दभः। क्रीळन्। नः। नुः।
रश्मे। आ। भुवः। सं। भस्मना। वायुना। वेविदानः। नाः। अस्य। सनत्। धृषजः। न। तिग्माः।
सुऽसंशिताः। वक्ष्यः। वक्षणेऽस्थाः॥ १३॥ ये। अग्ने। वाजऽसातम। त्वा। चित्। नाम। मन्य। से। ८

© Dharmartha Trust J&K. Digitized by eGangotri

रयिं। तं। नः। गीःऽभिः। श्रवाय्यं। देवऽत्रा। पनय। युजं। ये। अग्ने। न। ईरयंति। ते। वृद्धा
ः। उग्रस्य। शवसः। अप। द्वेषः। अप। ह्वरः। अन्यऽव्रतस्य। सश्चिरे। होतारं। त्वा। वृणी
महे। अग्ने। दक्षस्य। साधनं। यज्ञेषु। पूर्व्यं। गिरा। प्रयस्वंतः। हवामहे। इत्था। यथा।
ते। ऊतये। सहसाऽवन्। दिवेऽदिवे। राये। ऋताय। सुक्रतो इति सुऽक्रतो। गोभिः। स्या
म। सधऽमादः। वीरैः। स्याम। सधऽमादः॥ १२॥ मनुष्वत्। त्वा। नि। धीमहि। मनुष्वत्।
सं। इधीमहि। अग्ने। मनुष्वत्। अंगिरः। ०। त्वं। हि। मानुषे। जने। अग्ने। सुऽप्रीतः। इ
ध्यसे। स्रुचः। त्वा। यंति। आनुषक्। सुऽजात। सर्पिःऽआसुते। त्वां। विश्वे। सऽजोषसः॥

© Dharmartha Trust J&K. Digitized by eGangotri

च.प. देवासः। दूतं। अक्रत। सपर्यंतः। त्वा। कवे। यज्ञेषु। देवं। ईळते। देवं। वः। देवऽयज्यया। अ
८ ग्निं। ईळीत। मर्त्यः। संऽइद्धः। शुक्र। दीदिहि। ऋतस्य। योनिं। आ। असदः। ससस्य। यो
निं। आ। असदः। ३३। प्र। विश्वऽसामन्। अत्रिऽवत्। अर्च। पावकऽशोचिषे। यः। अध्व
8 रेषु। ईड्यः। होता। मंद्रऽतमः। विशि। अग्निं। जातऽवेदसं। दधात। देवं। ऋत्विजं। प्र।
यज्ञः। एतु। आनुषक्। अद्य। देवव्यचःऽतमः। चिकित्विन्ऽमनसं। त्वा। देवं। मर्तासः।
ऊतये। वरेण्यस्य। ते। अवसः। इयानासः। अमन्महि। अग्ने। चिकिद्धि। अस्य। नः। इदं।
वचः। सहस्य। तं। त्वा। सुऽशिप्र। दंऽपते। स्तोमैः। वर्धंति। अत्रयः। गीःऽभिः। शुंभंति। अ ८

© Dharmartha Trust J&K. Digitized by eGangotri

त्रेयः ॥ २४ ॥ अग्ने । सहंतं । आ । भर । द्युम्नस्य । प्रऽसहा । रयिं । विश्वाः । यः । चर्षणीः । अभि
अभि । आसा । वाजेषु । सासहत् । त्वं ॥ अग्ने । पृतनाऽसहं । रयिं । सहस्वः । आ । भर । त्वं । हि
सत्यः । अद्भुतः । दाता । वाजस्य । गोऽमतः ॥ विश्वे । हि । त्वा । सऽजोषसः । ~~देवासः~~ । जनासः ।
वृक्तऽबर्हिषः । होतारं । सद्मऽसु । प्रियं । व्यंति । वार्या । पुरु ॥ सः । हि । स्मा । विश्वऽचर्षणिः ।
अभिऽमाति । सहः । दधे । अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पा
वक । दीदिहि ॥ २५ ॥ अग्ने । त्वं । नः । अंतमः । उत । त्राता । शिवः । भव । वरूथ्यः ॥ वसुः । अ
ग्निः । वसुऽश्रवाः । अच्छ । नक्षि । द्युमत्ऽतमं । रयिं । दाः ॥ सः । नः । बोधि । श्रुधि । हवं । उरु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ वे॰ ष्या। नः। अघऽयतः। समस्मात्। तं। त्वा। शोचिष्ठ। दीदिवः। सुम्नाय। नूनं। ईमहे।
९ सखिऽभ्यः॥ १४॥ अछा। वः। अग्निं। अवसे। देवं। गासि। सः। नः। वसुः। रासत्। पु
९ त्रः। ऋषूणां। ऋतऽवा। पर्षति। द्विषः। सः। हि। सत्यः। यं। पूर्वे। चित्। देवासः। चित्।
यं। ईधिरे। होता। मन्द्रऽजिह्वः। इत्। सुदीतिऽभिः। विभाऽवसुं। सः। नः। धीती। वरि
ष्ठया। श्रेष्ठया। च। सुऽमत्या। अग्ने। रायः। दिदीहि। नः। सुवृक्तिऽभिः। वरेण्य। अ
ग्निः। देवेषु। राजति। अग्निः। मर्तेषु। आऽविशन्। अग्निः। नः। हव्यऽवाहनः। अग्निं।
धीभिः। सपर्यत। अग्निः। तुविश्रवःऽतमं। तुविऽब्रह्माणं। उत्ऽतमं। अतूर्तं। श्रा ९

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

वृषत्ऽपतिं । पुत्रं । ददाति । दाशुषे ॥ १७ ॥ अग्निः । ददाति । सत्ऽपतिं । ससाह । यः ।
युधा । नृऽभिः । अग्निः । अत्यं । रघुऽस्यदं । जेतारं । अपराऽजितं । यत् । वाहिष्ठं ।
तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभाऽवसो । महिषीऽइव । त्वत् । रयिः ।
त्वत् । वाजाः । उत् । ईरते ॥ तव । द्युऽमंतः । अर्चयः । ग्रावाऽइव । उच्यते । बृहत् । उतो इति ।
ते । तन्यतुः । यथा । स्वानः । अर्त्त । त्मना । दिवः ॥ एव । अग्निं । वसुऽयवः । सहसानं । ववंदि
म । सः । नः । विश्वाः । अति । द्विषः । पर्षत् । नावाऽइव । सुऽक्रतुः ॥ १८ ॥ अग्ने । पावक । रो
चिषा । मंद्रया । देव । जिह्वया । आ । देवान् । वक्षि । यक्षि । च ॥ तं । त्वा । घृतस्नो इति घृतऽ

प॰ च॰ स्तो। ईमहे। चित्रभानो इति चित्रऽभानो। स्वःऽदृशं। देवान्। आ। वीतये। वहा। वीतिऽहोत्रं।
१० त्वा। कवे। द्युऽमन्तं। सं। इधीमहि। अग्ने। बृहन्तं। अध्वरे। अग्ने। विश्वेभिः। आ। गहि।
देवेभिः। हव्यऽदातये। होतारं। त्वा। वृणीमहे। यजमानाय। सुन्वते। आ। अग्ने। सुऽवी
र्यं। वहा। ०॥ १९॥ संऽइधानः। सहस्रऽजित्। अग्ने। धर्माणि। पुष्यसि। देवानां। दूतः।
उक्थ्यः। ०। होत्रऽवाहं। यविष्ठ्यं। ०। स्तृणीत। बर्हिः। आऽसदे। आ। इदं। मरुतः। अश्वि
नां। मित्रः। सीदंतु। वरुणः। देवासः। सर्वया। विशा॥ २०॥ अनस्वंता। सत्ऽपतिः। मम
हे। मे। गावा। चेतिष्ठः। असुरः। मघोनः। त्रैवृष्णः। अग्ने। दशभिः। सहस्रैः। वैश्वानर। ३०

त्रिऽअरुणः। चिकेतुः। यः। मे। शता। च। विंशतिं। च। गोनां। हरी इति। च। युक्ता। सुऽधुरा।
ददाति। वैश्वानर। सुऽस्तुतः। वरूधानः। अग्ने। यच्छ। त्रिऽअरुणाय। शर्म। एव। ते। अग्ने।
सुऽमतिं। चकानः। नविष्ठाय। नवमं। त्रसदस्युः। यः। मे। गिरः। तुविऽजातस्य। पूर्वीः। युक्ते।
न। अभि। त्रिऽअरुणः। गृणाति। यः। मे। इति। प्रऽवोचति। अश्वऽमेधाय। सूरये। ददत्। ऋ
चा। सनिं। यते। ददत्। मेधां। ऋतऽयते। यस्य। मा। परुषाः। शतं। उतऽहर्षयंति। उक्षणः। अ
३७। श्वऽमेधस्य। दानाः। सोमाः। त्रिऽआशिरः। इंद्राग्नी इति। शतऽदाव्नि। अश्वऽमेधे। सुऽवी
र्यं। क्षत्रं। धारयतं। बृहत्। दिवि। सूर्यंऽइव। अजरं। ॥ २१॥ सं। ऽ इद्धः। अग्निः। दिवि। शोचिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ अश्रेत् । प्रत्यङ् । उषसं । उर्विया । वि । भाति । एति । प्राची । विश्वऽवारा । नमःऽभिः । देवान् ।
११ ईळाना । हविषा । घृताची ॥ सम्ऽइध्यमानः । अमृतस्य । राजसि । हविः । कृण्वंतं । सचसे ।
स्वस्तये । विश्वं । सः । धत्ते । द्रविणं । यं । इन्वसि । आतिथ्यं । अग्ने । नि । च । धत्ते । इत् । पुरः ॥ अ
ग्ने । शर्द्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । संतु । सं । जाःऽपत्यं । सुऽयमं ।
आ । कृणुष्व । शत्रुऽयतां । अभि । तिष्ठ । महांसि ॥ सम्ऽइद्धस्य । प्रऽमहसः । अग्ने । वंदे । तव ।
श्रियं । वृषभः । द्युम्नऽवान् । असि । सं । अध्वरेषु । इध्यसे ॥ सम्ऽइद्धः । अग्ने । आऽहुत । देवा
न् । यक्षि । सुऽअध्वर । त्वं । हि । हव्यऽवाट् । असि ॥ आ । जुहोत । दुवस्यत । अग्निं । प्रऽयति । ११

अध्वरे । गृणीध्वं । हव्यऽवाहने ॥ २२ ॥ त्री । अर्यमा । मनुषः । देवऽताता । त्री । रोचना । दिव्या ।
धारयंत । अर्चंति । त्वा । मरुतः । पूतऽदक्षाः । त्वं । एषां । ऋषिः । असि । धीरः । अनु । यत् । ईं ।
मरुतः । मंदसानं । आर्चन् । इंद्रं । पपिऽवांसं । सुतस्य । आ । अदत्त । वज्रं । अभि । यत् । अ
हिं । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊं इति । उत । ब्रह्माणः । मरुतः । मे । अस्य । इंद्रः । सो
मस्य । सुऽसुतस्य । पेयाः । तत् । हि । हव्यं । मनुषे । गाः । अविंदत् । अहन् । अहिं । पपिऽवान् ।
इंद्रः । अस्य । आत् । रोदसी इति । विऽतरं । वि । स्कभायत् । संऽविव्यानः । चित् । भियसे । मृ
गं । कः इति कः । जिगर्तिं । इंद्रः । अपऽजर्गुराणः । प्रति । श्वसंतं । अव । दानवं । हन्निति हन् । अध
ति ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ क्रत्वा। मघऽवन्। तुभ्यं। देवाः। अनु। विश्वे। अददुः। सोमऽपेयं। यत्। सूर्यस्य। हरितः। पतन्तीः।
१२ पुरः। सतीः। उपराः। एतशे। करिति कः। २५॥ नव। यत्। अस्य। नवतिं। च। भोगान्। साकं।
12 वज्रेण। मघऽवा। विऽवृश्चत्। अर्चन्ति। इन्द्रं। मरुतः। सधऽस्थे। त्रैस्तुभेन। वचसा। बाधत। द्यां।
सखा। सख्ये। अपचत्। तूयं। अग्निः। अस्य। क्रत्वा। महिषा। त्री। शतानि। त्री। साकं। इन्द्रः।
मनुषः। सरांसि। सुतं। पिबत्। वृत्रऽहत्याय। सोमं। त्री। यत्। शता। महिषाणां। अघः। माः।
त्री। सरांसि। मघऽवा। सोम्या। अपाः। कारं। न। विश्वे। अह्वन्त। देवाः। भरं। इन्द्राय। यत्। अ
हिं। जघान। उशना। यत्। सहस्यैः। अयातं। गृहं। इन्द्र। जूजुवानेभिः। अश्वैः। वन्वानः। अत्र। १२

© Dharmartha Trust J&K. Digitized by eGangotri

सऽरथं।ययाथ।कुत्सेन।देवैः।अवनोः।ह।शुष्णं।प्र।अन्यत्।चक्रं।अवृहः।सूर्यस्य।कुत्साय।
अन्यत्।वरिवः।यातवे।अकः।अनासः।दस्यून्।अमृणः।वधेन।नि।दुर्योणे।अ
वृणक्।मृध्रऽवाचः॥१०॥स्तोमासः।त्वा।गौरिऽवीतेः।अवर्धन्।अरंधयः।वैदथिनाय।पि
प्रुं।आ।त्वां।ऋजिश्वा।सख्याय।चक्रे।पचन्।पक्तीः।अपिबः।सोमं।अस्य।नवऽग्वासः।
सुतऽसोमासः।इंद्रं।दशऽग्वासः।अभि।अर्चंति।अर्कैः।गव्यं।चित्।ऊर्वं।अपिधानऽवं
तं।तं।चित्।नरः।शशमानाः।अप।व्रन्।कथो इति।नु।ते।परि।चराणि।विद्वान्।वीर्या।
मघऽवन्।या।चकर्थ।या।चो इति।नु।नव्या।कृणवः।शविष्ठ।प्र।इत्।ऊं इति।ता।ते।वि

© Dharmartha Trust J&K. Digitized by eGangotri

तस्योः

प॰ ५॰ रथेषु। ब्रवाम। एता। विश्वा। चकृऽवान्। इंद्र। भूरि। अपरिऽइता। जनुषा। वीर्येण। या। चित्।
१३. नु। वज्रिन्। कृणवः। दधृष्वान्। न। ते। वर्ता। तविष्याः। अस्ति। इंद्र। ब्रह्म। क्रियमाणा। जुष
13 स्व। या। ते। शविष्ठ। नव्याः। अकर्म। वस्त्राऽइव। भद्रा। सुऽकृता। वसुऽयुः। रथं। न। धीरः।
सुऽअपाः। अतक्षं॥ २५॥ कः। स्वः। वीरः। कः। अपश्यत्। इंद्रं। सुखऽरथं। ईयमानं। हरिऽ
भ्यां। यः। राया। वज्री। सुतऽसोमं। इच्छन्। तत्। ओकः। गंता। पुरुऽहूतः। ऊती। अव। अचच
क्षं। पदं। अस्य। सस्वः। उग्रं। निऽधातुः। अनु। आयं। इच्छन्। अपृच्छं। अन्यान्। उत। ते।
मे। आहुः। इंद्रं। नरः। बुबुधानाः। अशेम। प्र। नु। वयं। सुते। या। ते। कृतानि। इंद्र। ब्रवाम॥ १३

© Dharmartha Trust J&K. Digitized by eGangotri

यानि। नु। जुजोषः। वेदत्। अविद्वान्। शृणवत्। च। विद्वान्। वहते। अयं। मघऽवा। स
र्वऽसेनः। स्थिरं। मनः। चकृषे। जातः। इंद्र। वेषि। इत्। एकः। युधये। भूयसः। चित्।
अश्मानं। चित्। शवसा। दिद्युतः। वि। विदः। गवां। ऊर्वं। उस्रियाणां। परः। यत्। त्वं। प
रमः। आऽजनिष्ठाः। पराऽवति। श्रुत्यं। नाम। बिभ्रत्। अतः। चित्। इंद्रात्। अभयंत। दे
वाः। विश्वाः। अपः। अजयत्। दासऽपत्नीः॥ १७॥ तुभ्य। इत्। एते। मरुतः। सुऽशेवाः। अ
र्चंति। अर्कं। सुन्वंति। अंधः। अहिं। ओहानं। अपः। आऽशयानं। प्र। मायाभिः। मायि
नं। सक्षत्। इंद्रः। वि। सु। मृधः। जनुषा। दानं। इन्वन्। अहन्। गवा। मघऽवन्। संऽचका

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ नः। अत्र। दासस्य। नमुचेः। शिरः। यत्। अवर्त्तयः। मनवे। गातुं। इच्छन्। युजं। हि। मां। अ
३४ कृथाः। आत्। इत्। इंद्र। शिरः। दासस्य। नमुचेः। मथायन्। अश्मानं। चित्। स्वर्यं। वर्त्त
मानं। प्र। चक्रियाऽइव। रोदसी इति। मरुत्ऽभ्यः। स्त्रियः। हि। दासः। आयुधानि।
15 चक्रे। किं। मा। करन्। अबलाः। अस्य। सेनाः। अंतः। हि। अख्यत्। उभे इति। अस्य।
धेने इति। अथ। उप। प्र। ऐत्। युधये। दस्युं। इंद्रः। सं। अत्र। गावः। अभितः। अनवं
त। इहऽइह। वत्सैः। विऽयुताः। यत्। आसन्। सं। ताः। इंद्रः। असृजत्। अस्य। शाकैः।
यत्। ईं। सोमासः। सुऽसुताः। अमंदन्। ॥ २७॥ यत्। ईं। सोमाः। बभ्रुऽधूताः। अमंद ३४

© Dharmartha Trust J&K. Digitized by eGangotri

न्॥ अरोरवीत्। वृषभः। सदनेषु। पुरंऽदरः। पपिऽवान्। इंद्रः। अस्य। पुनः। गवां। अददात्। उ
स्रियाणां॥ भद्रं। इदं। रुशमाः। अग्ने। अक्रन्। गवां। चत्वारि। ददतः। सहस्रा। ऋणंऽचय
स्य। प्रऽयता। मघानि। प्रति। अग्रभीष्म। नृऽतमस्य। नृणां॥ सुऽपेशसं। मा। अव। सृजंति।
अस्तं। गवां। सहस्रैः। रुशमासः। अग्ने। तीव्राः। इंद्रं। अममंदुः। सुतासः। अक्तोः। विऽउष्टौ।
परिऽतक्म्यायाः॥ औछत्। सा। रात्री। परिऽतक्म्या। यां। ऋणंऽचये। राजनि। रुशमानां।
अत्यः। न। वाजी। रघुः। अज्यमानः। बभ्रुः। चत्वारि। असनत्। सहस्रा॥ चतुःऽसहस्रं। ग
व्यस्य। पश्वः। प्रति। अग्रभीष्म। रुशमेषु। अग्ने। घर्मः। चित्। तप्तः। प्रऽवृजे। आसीत्। यः।

© Dharmartha Trust J&K. Digitized by eGangotri

प० चं अथुस्मा यः। नो। ऊं इति। आ। दाम। विप्राः। रणा। इंद्रः। रथा। या। मे ऽ वत्। कृणोति। यं। अस्थात्। धिऽ अ
३५ मघऽवा। वाजऽ युनं। यूथाऽइव। पश्वः। विऽउनोति। गोपाः। अरिष्टः। याति। प्रथमः। सिसा
15 सन्। आ। प्राऽद्रवा। हरिऽवः। मा। वि। वेनः। पिशंगऽराते। अभि। नः। सच। स्वा। न हि। त्वत्। इंद्र
वस्यः। अन्यत्। अस्ति। अमेनान्। चित्। जनिऽवतः। चकर्थ। उन्नाय त्। सहऽसः। सहः। आ
अजनिष्ठाः। दिदिष्टे। इंद्रः। इंद्रियाणि। विश्वा। प्रा। अचोदयत्। सुऽदुघाः। वव्रे। अंतः। विऽज्यो
तिषा। संऽववृत्वत्। तमः। अवऽरित्यवः। अनवः। नो। रथा। अश्वा। या। लक्ष्म। सुष्णा। वज्रो। पु
रुहूत। द्युऽमंतं। ब्रह्माणः। इंद्र। महयंतः। अर्कैः। अवर्धयन्। अहये। हंतवै। ऊं इति। श्लोऽय १५

अर्कैः।

तु। ते। वृषणः। अर्चान्। इन्द्रं। ग्रा। वाणः। अदितिः। सऽजोषाः। अनश्वासः। ये। पवयः। अर
थाः। इन्द्रऽइषिताः। अभि। अवर्तन्त। दस्यून्। र४। प्र। ते। पूर्वाणि। करणानि। वोचं। प्र।
नूतना। मघऽवन्। या। चकर्थ। शक्तिऽवः। यत्। विऽभराः। रोदसी इति। उभे इति। जयन्।
अपः। मनवे। दानुऽचित्राः। तत्। इत्। नु। ते। करणं। दस्म। विप्र। अहिं। यत्। घ्नन्। ओजः।
अत्र। अमिमीथाः। शुष्णस्य। चित्। परि। मायाः। अगृभ्णाः। प्रऽपित्वं। यन्। अप। द
स्यून्। असेधः। त्वं। अपः। यदवे। तुर्वशाय। अरमयः। सुऽदुघाः। पारः। इन्द्र। उग्रं। अ
यातं। अवहः। ह। कुत्सं। सं। ह। यत्। वां। उशना। अरन्त। देवाः। इन्द्रा। कुत्सा। वहमाना।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ रथेन। आ। वां। अस्याः। अपि। कर्णे। वहं। तु। निः। सीं। अत्रऽभ्यः। धमथः। निः। सधऽस्थात्।
१६ मघोनः। हृदः। वरथः। तमांसि। वातस्य। युक्तान्। सुऽयुजः। चित्। अश्वान्। कविः। चि-
त्। एषः। अजगन्। अवस्युः। विश्वा। ता। अत्र। मरुतः। सखा। यः। इंद्र। ब्रह्माणि। तविषीं।
16 अवर्धन्॥ ३०॥ स्तरः। चित्। रथं। परिऽतक्म्यायां। पूर्वं। करत्। उपरं। जूजुऽवांसं। भरत्।
चक्रं। एतशः। सं। रिणाति। पुरः। दधत्। सनिष्यति। क्रतुं। नः। आ। अयं। जनाः। अभिऽच-
क्षे। जगाम। इंद्रः। सखायं। सुतऽसोमं। इच्छन्। वदन्। ग्रावा। अव। वेदिं। भ्रियाते। य-
स्य। जीरं। अध्वर्यवः। चरंति। ये। चाकनंत। चाकनंत। नु। ते। मर्ताः। अमृत। मो इति। १६

© Dharmartha Trust J&K. Digitized by eGangotri

तो।अंहः।आ।अरत्ना।ववंधि।यज्यून्।उत।तेषु।धेहि।ओजः।जनेषु।येषु।ते।स्याम।३४॥
अर्दर्दः।उत्सं।असृजः।वि।खानि।त्वं।अर्णवान्।बद्बधानान्।अरम्णाः।महांतं।इंद्र। ना
पर्वतं।वि।यत्।व रिति वः।सृजः।वि।धाराः।अव।दानवं।हन्निति हन्।त्वं।उत्सान्।
ना ऋतुऽभिः।बद्बधानान्।अरंहः।ऊधः।पर्वतस्य।वज्रिन्।अहिं।चित्।उग्र।प्रऽयुतं।शया
नं।जघन्वान्।इंद्र।तविषीं।अधत्थाः।त्यस्य।चित्।महतः।निः।मृगस्य।वधः।जघा
न।तविषीभिः।इंद्रः।यः।एकः।इत्।अप्रतिः।मन्यमानः।आत्।अस्मात्।अन्यः।अज
निष्ट।तव्यान्।त्यं।चित्।एषां।स्वधया।मदंतं।मिहः।नपातं।सुऽवृधं।तमःऽगां।व

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰
३७

17

षऽप्रभर्मा। दानवस्य। भाम। वज्रेण। वज्री। नि। जघान। शुष्णं। त्यं। चित्। अस्य। क्रतुऽ
भिः। निऽसत्तं। अमर्मणः। विदत्। इत्। अस्य। मर्म। यत्। ईं। सुऽक्षत्र। प्रऽभृता। मदस्य।
युयुत्संतं। तमसि। हर्म्ये। धाः। त्यं। चित्। इत्था। कत्पयं। शयानं। असूर्ये। तमसि। ववृधा
नं। तं। चित्। मंदानः। वृषभः। सुतस्य। उच्चैः। इंद्रः। अपऽगूर्य। जघान। उत्। यत्। इंद्रः।
महते। दानवाय। वधः। यमिष्ट। सहः। अप्रतिऽइतं। यत्। ईं। वज्रस्य। प्रऽभृतौ। ददाभ। वि
श्वस्य। जंतोः। अधमं। चकार। त्यं। चित्। अर्णं। मधुऽपं। शयानं। असिन्वं। वव्रं। महि। आ
दत्। उग्रः। अपादं। अत्रं। महता। वधेन। नि। दुर्योणे। अवृणक्। मृध्रऽवाचं। कः। अस्य। १८

© Dharmartha Trust J&K. Digitized by eGangotri

शुष्मं । तविषीं । वरा । ते । एकः । धना । भरते । अप्रतिऽइतः । इमे इति । चित्त । अस्य । अयसः । नु ।
सः देवी इति । इंद्रस्य । ओजसः । भियसा । जिहाते इति । नि । अस्मै । देवी । स्वऽधितिः । जिहीते । इंद्रा
य । गातुः । उशतीऽइव । येमे । सं । यत् । ओजः । युवते । विश्वं । आभिः । अनु । स्वधाऽव्ने । क्षितयः ।
नमंत । एकं । नु । त्वा । सत्ऽपतिं । पांचऽजन्यं । जातं । शृणोमि । यशसं । जनेषु । तं । मे । जगृभ्रे ।
आऽशसः । नविष्ठं । दोषा । वस्तोः । हवमानासः । इंद्रं । एव । अहिं । त्वां । ऋतुऽथा । यातयंते । म
घा । विप्रेभ्यः । ददतं । शृणोमि । किं । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाऽया । निऽदधुः ।
कामं । इंद्र ॥ २३ ॥ चतुर्थोष्टके पदे प्रथमोध्यायः ॥ हरिः ॐ ॥ महि दशप्राजामत्यः सव

© Dharmartha Trust J&K. Digitized by eGangotri

प॰चं॰ रणो माल शङ्गुं नव त्रिष्टुबंतं यस्ते ष्टौ प्र भूवसुरांगिरसः पंक्त्यंतं स आगमत् षट् तृतीया
१८ जगती सं भानुना पंचात्रिरुरो नु रोह्नु भं यदिंद्र पंक्त्यंतं मा याहि नव ष्च्यु च्छि गाग्ध्यं सा
नुष्टुप्मध्ये च सा सौरी तदा दीति हास स्तुति कर्मत्वा दत्रिरेव देवः का नु विंशति वैश्वदेवं
18 वैन खोक श्याच्याति जगत्यावं सैकपदा त्रिशंतमा भूनैकादशी रोक्त्याधेन वस्त्रनैतया
रूपां स्यैकपदांतं प्रत्न थापंचोना काश्यपो वत्सारान्यै च ऋषयो त्रदृष्टलिंगाद्वित्रिष्टुबंतं वि
दाएकादशा सदापृणो हयो ष्टौ प्रतिक्षत्रौ स्याह्व चो देवपत्नीस्त्वौ त्या त्रिष्टुप् द्वितीया चं॥२४॥
हरिः ॐ॥ महि। महो। तव। सो। दी। ध्यो। नू। नो। इंद्राय। इत्था। तव सो। अर्ना। त्या नो। यः। अ। सं। १८

© Dharmartha Trust J&K. Digitized by eGangotri

सुऽमतिं। वाजेऽसातौ। स्तुतः। जनेः। सुऽमर्यैः। चिकेत। स्वः। त्वां। नरः। धियसानः। इंद्रं। अर्कैः। ह
रीणां। वृषन्। योक्त्रं। अश्रेः। याः। इत्था। मघऽवन्। अनु। जोषं। वक्षः। अभि। प्र। अर्यः। सक्षि।
जनान्। ना। ते। तु। इंद्र। अभि। अस्मत्। ऋष्वा। अयुक्ता। सः। अवप्नता। यत्। असन्। तिष्ठा। र
थं। अधि। तं। वज्रऽहस्त। आ। रश्मिं। देव। यमसे। सुऽअश्वः। पुरु। यत्। ता। तो। इंद्र। सं। ति। रु
क्षा। गवे। चकर्थ। उर्वरासु। युध्यन्। ततक्षे। सूर्याय। चित्। ओकसि। स्वे। वृषा। स
मत्ऽसु। दासस्य। नाम। चित्। वयं। ते। ते। इंद्र। ये। च। नरः। शर्धः। जज्ञानाः। याताः। च।
रथाः। आ। अस्मान्। जगम्यात्। अहिऽशुष्म। सत्वा। भगः। न। हव्यः। प्रऽभृथेषु। चारुः।।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ ।।१।। पुपृक्षेण्यं। इंद्र। त्वे इति। हि। ओजः। नृम्णानि। च। नृतमानः। अमर्त्तः। सः। नः। ए
१९ नीं। वसवानः। रयिं। दाः। प्र। अर्यः। स्तुषे। तुविऽमघस्य। दानं। एव। नः। इंद्र। ऊतिऽभिः।
अव। पाहि। गृणतः। शूर। कारून्। उत। त्वचं। ददतः। वाजऽसातौ। पिप्रीहि। मध्वः। सुऽ
19 सुतस्य। चारोः। उत। त्ये। मा। पौरुऽकुत्स्यस्य। सूरेः। त्रसदस्योः। हिरणिनः। रराणाः।
वहंतु। मा। दश। श्येतासः। अस्य। गैरिऽक्षितस्य। क्रतुऽभिः। नु। सश्चे।०। मारुतऽअश्व
स्य। शोणाः। क्रत्वाऽमघासः। विदथस्य। रातौ। सहस्रा। मे। च्यवतानः। ददानः। आ
नूकं। अर्यः। वपुषा। न। आर्चत्।०। ध्वन्यस्य। जुष्टाः। लक्ष्मण्यस्य। सुऽरुचः। यतानः। १९

© Dharmartha Trust J&K. Digitized by eGangotri

मह्ना। रायः। संऽवरणस्य। ऋषेः। व्रजं। न। गावः। प्रऽयताः। अपि। ग्मन्॥र॥ अजातऽश
त्रुं। अजरा। स्वःऽवती। अनु। स्वधा। अमिता। दस्मं। ईयते। सुनोतन। पचत। ब्रह्मऽवाहसे। ह
पुरुऽस्तुताय। प्रऽतरं। दधातन। आ। यः। सोमेन। जठरे। अपिप्रत। अमंदत। मघऽवा।
मध्वः। अंधसः। यत्। ईं। मृगाय। हंतवे। महाऽवधः। सहस्रऽभृष्टिं। उशना। वधं। यम
त्। यः। अस्मै। घ्रंसे। उत। वा। यः। ऊधनि। सोमं। सुनोति। भवति। द्युऽमान्। अह। अपऽ
अप। शक्रः। ततनुष्टिं। ऊहति। तनूऽशुभ्रं। मघऽवा। यः। कवऽसखः। यस्य। अवधी
त्। पितरं। यस्य। मातरं। यस्य। शक्रः। भ्रातरं। न। अतः। ईषते। वेति। ऊं इति। अस्य।

इत

© Dharmartha Trust J&K. Digitized by eGangotri

प॰चे॰ प्रऽयता। यतंऽकरः। न। किल्बिषात्। ईषते। वस्वः। आऽकरः। न। पंचऽभिः। दशऽभिः।
२० वष्टि। आऽरभं। न। असुन्वता। सचते। पुष्यता। चन। जिनाति। वा। इत्। अमुया। हं
ति। वा। धुनिः। आ। देवऽयुं। भजति। गोऽमति। व्रजे॥ ५॥ विऽत्वक्षणः। संऽऋतौ। च
क्रंऽआसजः। असुन्वतः। विषुणः। सुन्वतः। वृधः। इंद्रः। विश्वस्य। दमिता। विऽभीष
णः। यथाऽवशं। नयति। दासं। आर्यः। सं। ई। पणेः। अजति। भोजनं। मुषे। वि। दा
शुषे। भजति। सूनरं। वसु। दुःऽगे। चन। ध्रियते। विश्वः। आ। पुरु। जनः। यः। अस्य।
तविषीं। अचुक्रुधत्। सं। यत्। जनौ। सुऽधनौ। विश्वऽशर्धसौ। अवेत्। इंद्रः। मघऽ २०

20

© Dharmartha Trust J&K. Digitized by eGangotri

वा। गोषु। अश्विषु। शुभ्रिषु। युजं। हि। अन्यं। अकृत। प्रऽवेपनी। उत्। ईं। गव्यं। सृजते। सत्वऽभिः। धु
निः। सहस्रऽसां। आग्निऽवेशिं। गृणीषे। शत्रिं। अग्ने। उपऽमां। केतुं। अर्यः। तस्मै। आ
पः। संऽयतः। पीपयन्त। तस्मिन्। क्षत्रं। अमऽवत्। त्वेषं। अस्तु॥४॥ यः। ते। साधिष्ठः। अव
से। इंद्र। क्रतुः। तं। आ। भर। अस्मभ्यं। चर्षणिऽसहं। सस्निं। वाजेषु। दुस्तरं। यत्। इंद्र। ते। च
तस्रः। यत्। शूर। संति। [illegible]। तिस्रः। यत्। वा। पंच। क्षितीनां। अवः। तत्। सु। नः। आ। भर।
आ। ते। अवः। वरेण्यं। वृषन्ऽतमस्य। हूमहे। वृषऽजूतिः। हि। जज्ञिषे। आऽभूभिः। इंद्र।
तुर्वणिः। वृषा। हि। असि। राधसे। जज्ञिषे। वृष्णि। ते। शवः। स्वऽक्षत्रं। ते। धृषत्। मनः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चं॰ सत्राऽहं। इंद्र। पौंस्यं। त्वं। तं। इंद्र। मर्त्यं। अमित्रऽयंतं। अद्रिऽवः। सर्वऽरथा। शतक्रतो इति शत
२३ तऽक्रतो॥ नि। याहि। शवसः। पते॥ ५॥ त्वां। इत्। वृत्रहन्ऽतम। जनासः। वृक्तऽबर्हिषः। उग्रं।
पूर्वीषु। पूर्व्यं। हवंते। वाजऽसातये। अस्माकं। इंद्र। दुस्तरं। पुरःऽयावानं। आजिषु। सऽयावानं। या
21 धनेऽधने। वाजऽयंतं। अव। रथं। अस्माकं। इंद्र। आ। इहि। नः। रथं। अव। पुरंऽध्या। वयं।
शविष्ठ। वार्यं। दिवि। श्रवः। दधीमहि। दिवि। स्तोमं। मनामहे॥ ६॥ सः। आ। गमत्। इंद्रः। यः।
वसूनां। चिकेतत्। दातुं। दामनः। रयीणां। धन्वऽचरः। न। वंसगः। तृषाणः। चकमानः। पिबतु।
दुग्धं। अंशुं। आ। तं। हनू इति। हरिऽवः। शूर। शिप्रे इति। हनू। सोमः। न। पर्वतस्य। पृष्ठे। २१

© Dharmartha Trust J&K. Digitized by eGangotri

अनु। त्वा। राजन्। अर्वतः। न। हिन्वन्। गीःऽभिः। मदेम। पुरुऽहूत। विश्वे। चक्रं। न। वृत्तं।
पुरुऽहूत। वेपते। मनः। भिया। मे। अमतेः। इत्। अद्रिऽवः। रथात्। अधि। त्वा। जरिता।
सदाऽवृधा। कुवित्। नु। स्तोषत्। मघऽवन्। पुरुऽवसुः। एषः। ग्रावाऽइव। जरिता। ते।
इन्द्र। इयर्त्ति। वाचं। बृहत्। आऽशुषाणः। प्र। सव्येन। मघऽवन्। यंसि। रायः। प्र। दक्षिणित्।
हरिऽवः। मा। वि। वेनः। वृषा। त्वा। वृषणं। वर्धतु। द्यौः। वृषा। वृषऽभ्यां। वहसे। हरिऽभ्यां।
सः। नः। वृषा। वृषऽरथः। सुऽशिप्र। वृषक्रतो इति वृषऽक्रतो। वृषा। वज्रिन्। भरे। धाः।
यः। रोहितौ। वाजिनौ। वाजिनीऽवान्। त्रिऽभिः। शतैः। सचमानौ। अदिष्ट। यूने। सं।

© Dharmartha Trust J&K. Digitized by eGangotri

फ.चं. अस्मै।सितयः।नमंता।श्रुतऽरथाय।मरुतः।दुवःऽया॥७॥सं।भानुना।यतते।सूर्यस्य।
२२ आऽजुह्वानः।घृतऽपृष्ठः।सुऽअंचाः।तस्मै।अमृध्राः।उषसः।वि।उच्छान्।यः।इंद्राय।सु
22 नवाम।इति।आह।सम्ऽइद्धऽअग्निः।वनवत्।स्तीर्णऽबर्हिः।युक्तऽग्रावा।सुतऽसोमः।ज
राते।ग्रावाणः।यस्य।इषिरं।वदंति।अयत्।अध्वर्युः।हविषा।अव।सिंधुं।वधूः।इयं।
पतिं।इच्छंती।एति।यः।ईं।वहाते।महिषीं।इषिरां।आ।अस्य।श्रवस्यात्।रथः।आ।च।घो
षात्।पुरु।सहस्रा।परि।वर्तयाते।न।सः।राजा।व्यथते।यस्मिन्।इंद्रः।तीव्रं।सोमं।पि
बति।गोऽसखायं।आ।सत्वनैः।अजति।हंति।वृत्रं।क्षेति।क्षितीः।सुऽभगः।नाम।पु २२

© Dharmartha Trust J&K. Digitized by eGangotri

ष्यन्। अप्रऽभ्यां तं। क्षेमे। अभि। योगे। भवाति। उभे इति। वृतौ। संयती इति संऽयती। सं

जयाति। प्रियः। सूर्ये। प्रियः। अग्ना। भवाति। यः। इन्द्राय। सुतऽसोमः। ददाशत्॥ ८॥

पुरोः। ते। इन्द्र। राधसः। विऽभ्वी। रातिः। शतक्रतो इति शतऽक्रतो। अध। नः। विश्वऽच

र्षणे। द्युम्ना। सुऽक्षत्र। मंहय। यन्तं। ईं। इन्द्र। श्रवाय्यं। इषं। शविष्ठ। दधिषे। पप्रथे। दी

र्घश्रुत्ऽतमं। हिरण्यऽवर्ण। दुस्तरं। शुष्मासः। ये। ते। अद्रिऽवः। मेहना। केतऽसापः।

उभा। देवौ। अभिष्टये। दिवः। च। ग्मः। च। राजथः। उतो इति। नः। अस्य। कस्य। चित्।

दक्षस्य। तव। वृत्रऽहन्। अस्मभ्यं। नृम्णं। आ। भर। अस्मभ्यं। नृऽमणस्यसे। नु। ते।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ त्र॰ आभिः।अभिष्टिऽभिः।तव।शर्मन्।शतक्रतो इति शतऽक्रतो।इंद्र।स्याम।सुऽगोपाः
२३ ।शूर।स्याम।सुऽगोपाः॥७॥यत्।इंद्र।चित्र।मेहना।अस्ति।त्वाऽदातं।अद्रिऽवः।
राधः।तत्।नः।विदद्वसो इति विदत्ऽवसो।उभयाहस्ति।आ।भर।यत्।मन्यसे।व
23 रेण्यं।इंद्र।द्युक्षं।तत्।आ।भर।विद्याम।तस्य।ते।वयं।अकूपारस्य।दावनेः।यत्।ते
दित्सु।प्रऽराध्यं।मनः।अस्ति।श्रुतं।बृहत्।तेन।दृळ्हा।चित्।अद्रिऽवः।आ।वाजं।
दर्षि।सातये।मंहिष्ठं।वः।मघोनां।राजानं।चर्षणीनां।इंद्रं।उप।प्रऽशस्तये।पूर्वी
भिः।जुजुषे।गिरः।अस्मै।इत्।काव्यं।वचः।उक्थं।इंद्राय।शंस्यं।तस्मै।ऊं इति। २३

© Dharmartha Trust J&K. Digitized by eGangotri

ब्रह्मऽवाहसे। गिरः। वर्द्धंति। अत्रयः। गिरः। शुंभंति। अत्रयः॥१०॥ आ। याहि।
अद्रिऽभिः। सुतं। सोमं। सोमऽपते। पिब। वृषन्। इंद्र। वृषऽभिः। वृत्रहन्ऽतम। आ। वृ
षा। ग्रा। वा। वृषा। मदः। वृषा। सोमः। अयं। सुतः॥०॥ वृषा। त्वा। वृषणं। हुवे। वज्रि
न्। चित्राभिः। ऊतिऽभिः॥०॥ ऋजीषी। वज्री। वृषभः। तुराषाट्। शुष्मी। राजा। वृ
त्रऽहा। सोमऽपावा। युक्त्वा। हरिऽभ्यां। उप। यासत्। अर्वाङ्। माध्यंदिने। सवने।
मत्सत्। इंद्रः। यत्। त्वा। सूर्य। स्वःऽभानुः। तमसा। अविध्यत्। आसुरः। अक्षेत्र
ऽवित्। यथा। मुग्धः। भुवनानि। अदीधयुः॥११॥ स्वःऽभानोः। अध। यत्। इंद्र

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चै॰ मायाः। अव। दिवः। वर्तमानाः। अव। अहन्। गूळ्हं। सूर्यं। तमसा। अपऽव्रतेन। तु
२४ रीयेण। ब्रह्मणा। अविंदत्। अत्रिः॥ मा। मां। इमं। तव। संतं। अत्रे। इरस्या। द्रुग्धः।
भियसा। नि। गारीत्। त्वं। मित्रः। असि। सत्यऽराधाः। तौ। मा। इह। अवतं। वरु
24 णः। च। राजा॥ ग्राव्णः। ब्रह्मा। युयुजानः। सपर्यन्। कीरिणा। देवान्। नमसा।
उपऽशिक्षन्। अत्रिः। सूर्यस्य। दिवि। चक्षुः। आ। अधात्। स्वःऽभानोः। अप। मा
याः। अघुक्षत्॥ यं। वै। सूर्यं। ०। अत्रयः। तं। अनु। अविंदन्। नहि। अन्ये। अश
कुवन्॥ ३॥ २॥ कः। नु। वां। मित्रावरुणौ। ऋतऽयन्। दिवः। वा। महः। पार्थिवस्य। २४

© Dharmartha Trust J&K. Digitized by eGangotri

वा । दे । ऋतस्य । वा । सदसि । त्रासीथां । नः । यज्ञऽयज्ञे । वा । पशुऽसः । ना । वाजा

न्ना । ते । ० । जुषंत । न मःऽभिः । वा । यो । दधते । सुऽशक्तिः । स्तोमं । रुद्राय । मीढुषे ।

सऽजोषाः । आ । वां । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य । पुष्टौ ।

उत । वा । दिवः । असुराय । मन्म । प्र । अंधांसिऽइव । यज्यवे । भरध्वं । प्र । सक्षणः ।

दिव्यः । कण्वऽहोता । त्रितः । दिवः । सऽजोषाः । वातः । अग्निः । पूषा । भगः । प्रऽभृ

थे । विश्वऽभोजाः । आजिं । न । जग्मुः । आश्वश्वऽतमाः । प्र । वः । रयिं । युक्तऽअ

श्वं । भरध्वं । रायः । एषे । अवसे । दधीत । धीः । सुऽशेवः । एवैः । औशिजस्य । होता

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चं॰ ता । ये । वः । एवैः । मरुतः । तुराणां ॥ ३ ॥ प्र । वायुं । रथऽयुजं । कृणुध्वं । प्र ।
२५ देवं । विप्रं । पनितारं । अर्कैः । इषुध्यवः । ऋतऽसापः । पुरंऽधीः । वस्वीः ।
नः । अत्र । पत्नीः । आ । धियो । धुरिति धुः । १० । वंद्येभिः । शूषैः । प्र । यह्वी इति ।
25 दिवः । चितयत्ऽभिः । अर्कैः । उषसानक्ता । विदुषी इवेति विदुषीऽइव । विश्वं ।
आ । हा । वहतः । मर्त्याय । यज्ञं । अभि । वः । अर्चे । पोष्याऽवतः । नॄन् । वास्तोः ।
पतिं । त्वष्टारं । रराणः । धन्या । सऽजोषाः । धिषणा । नमःऽभिः । वनस्पतीन् ।
एषे । ओषधीः । रायः । एषे । तुजे । नः । तने । पर्वताः । संतु । स्वऽएतवः । ये । वसवः । २५

© Dharmartha Trust J&K. Digitized by eGangotri

ना । वीराः । पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसं । नर्यः । अभिष्टौ । वरूथः । अस्तो

षि । भूम्यस्य । गर्भं । त्रितः । नपातं । अपां । सुऽवृक्ति । गृणीते । अग्निः । एतरि । ना । भूषैः । शो

चिःऽकेशः । नि । रिणाति । वना ॥ १४ ॥ कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितु

षे । भगाय । आपः । ओषधीः । उत । नः । अवंतु । द्यौः । वना । गिरयः । वृक्षऽकेशाः । शृण्वंतु । नः ।

ऊर्जां । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा । शृण्वंतु । आपः । पुरः । न । शुभ्राः ।

परि । स्रुचः । बबृहाणस्य । अद्रेः । विद । चित् । नु । महांतः । ये । वः । एवाः । ब्रवाम । दस्माः ।

वार्यं । दधानाः । वयः । चन । सुऽभ्वः । आ । अव । यंति । क्षुभा । मर्तं । अनुऽयतं । वधऽस्नैः । आ

© Dharmartha Trust J&K. Digitized by eGangotri

प.५. दैव्यानि।पार्थिवानि।जन्म।अपः।च।अच्छ।सुऽमखाय।वोचं।वर्धंतां।द्यावः।गिरः।चंद्रऽ
२८ अग्राः।उदा।वर्धंतां।अभिऽसाताः।अर्णाः।पदेऽपदे।मे।जरिमा।नि।धायि।वरूत्री।
वा।शक्रा।या।पायुऽभिः।च।सिसक्तु।माता।मही।रसा।नः।स्मत्।सूरिऽभिः।ऋजुऽह
26 स्ता।ऋजुऽवनिः।१५। कथा।दाशेम।नमसा।सुऽदानून्।एवया।मरुतः।अच्छऽउ
क्तौ।प्रऽश्रवसः।मरुतः।अच्छऽउक्तौ।मा।नः।अहिः।बुध्न्यः।रिषे।धात्।अस्माकं।भूत्
उपमातिऽवनिः।इति।चित्।नु।प्रऽजायै।पशुऽमत्यै।देवासः।वनते।मर्त्यः।वः।
आ।देवासः।वनते।मर्त्यः।वः।अत्र।शिवां।तन्वः।धासिं।अस्याः।जरां।चित्।मे। २८

© Dharmartha Trust J&K. Digitized by eGangotri

यं

निःऽऋतिः। अजगन्। सीता। तां। वः। देवाः। सुऽमतिं। ऊर्जनीं। इषं। अश्याम। वसवः। शसा। गोः।
सा। नः। सुऽदानुः। मृळयंती। देवी। प्रति। द्रवंती। सुविताय। गम्याः। अभि। नः। इळा। यू
थस्य। माता। स्मत्। नदीभिः। उर्वशी। वा। गृणातु। उर्वशी। वा। बृहत्ऽदिवा। गृणाना।
अभिऽऊर्ण्वाना। प्रऽभृथस्य। आयोः। सिसक्तु। नः। ऊर्जव्यस्य। पुष्टेः। ॥३॥ शं। मा
वरुणो। दीधीती। गीः। मित्रं। भगं। अदितिं। नूनं। अश्याः। पृषत्ऽयोनिः। पंचऽहोता।
शृणोतु। अतूर्तऽपंथाः। असुरः। मयःऽभुः। प्रति। मे। स्तोमं। अदितिः। जगृभ्यात्। सू
नुं। न। माता। हृद्यं। सुऽशेवं। ब्रह्म। प्रियं। देवऽहितं। यत्। अस्ति। अहं। मित्रावरुणा।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.च. यता।मृधः।भुः।उत।ईरया।कविः।तमः।कवीनां।उनत्त।एनं।अभि।मध्वा।घृतेन।सः।नः।
२७ ।वसु।नि।प्रऽयंता।हिता।नि।चंद्राणि।देवः।सविता।सुवाति।सं।नः।इंद्र।मनसा।नेषि।
गोभिः।सं।सूरिऽभिः।हरिऽवः।सं।स्वस्ति।सं।ब्रह्मणा।देवऽहितं।यत्।अस्ति।सं।दे
27 वानां।सुऽमत्या।यज्ञियानां।देवः।भगः।सविता।रायः।अंशः।इंद्रः।वृत्रस्य।संऽजि
तः।धनानां।ऋभुक्षाः।वाजः।उत।वा।पुरंऽधिः।अवंतु।नः।अमृतासः।तुरासः।।१०।।
मरुत्वतः।अप्रतिऽइतस्य।जिष्णोः।अजूर्यतः।प्र।ब्रवाम।कृतानि।न।ते।पूर्वे।मघऽ
वन्।न।अपरासः।न।वीर्यं।नूतनः।कः।चन।आप।उप।स्तुहि।प्रथमं।रत्नऽधेयं। २७

© Dharmartha Trust J&K. Digitized by eGangotri

बृहस्पतिः। सनिता। राधनानां। यः। शंसते। स्तुवते। शंऽभविष्ठः। पुरुऽवसुः। आऽगमत्। जो
हुवानं। तव। ऊतिऽभिः। सचमानाः। अरिष्टाः। बृहस्पते। मघऽवानः। सुऽवीराः। ये। अश्वऽ
दाः। उत। वा। संति। गोऽदाः। ये। वस्त्रऽदाः। सुऽभगाः। तेषु। रायः। विऽसर्माणं। कृणुहि। वि
त्तं। एषां। ये। भुंजते। अपृणंतः। नः। उक्थैः। अपऽव्रतान्। प्रऽसवे। वऽवृधानान्। ब्रह्मऽ
द्विषः। सूर्यात्। यवयस्व। यः। ओहते। रक्षसः। देवऽवीतौ। अचक्रेभिः। तं। मरुतः। नि। या
त। यः। वः। शमीं। शशमानस्य। निंदात्। तुच्छ्यान्। कामान्। करते। सिस्विदानः॥१८॥
तं। ऊं इति। स्तुहि। यः। सुऽइषुः। सुऽधन्वा। यः। विश्वस्य। क्षयति। भेषजस्य। यक्ष्व।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰वे॰ मुहः। सौमनसाय। रुद्रं। नमःऽभिः। देवं। असुरं। दुवस्य। दमूनसः। अपसः। येऽसुऽहस्ताः
२८ । वृष्णः। पत्नीः। नद्यः। विभ्वऽतष्टाः। सरस्वती। बृहत्ऽदिवा। उत। राका। दशस्यंतीः। वरि
वस्यंतु। शुभ्राः। प्र। सु। मुहे। सुऽशरणाय। मेधां। गिरं। भरे। नव्यसीं। जायमानां। यः।
28· अहनाः। दुहितुः। वक्षणासु। रूपा। मिनान्। अकृणोत्। इदं। नः। प्र। सुऽस्तुतिः। स्तनयंतं
तं। रुवंतं। इळः। पतिं। जरितः। नूनं। अश्याः। यः। अब्धिऽमान्। उदनिऽमान्। इयर्ति। प्र। विऽ
द्युता। रोदसी इति। उक्षमाणः। एषः। स्तोमः। मारुतं। शर्धः। अच्छ। रुद्रस्य। सूनून्। युव
न्यून्। उत्। अश्याः। कामः। राये। हवते। मा। स्वस्ति। उप। स्तुहि। पृषत्ऽअश्वान्। अयासः। २८

© Dharmartha Trust J&K. Digitized by eGangotri

प्र। एषः। स्तोमः। पृथिवीं। अंतरिक्षं। वनस्पतीन्। ओषधीः। राये। अश्याः। देवःऽदेवः। सुऽहवः
। भूतु। मह्यं। मा। नः। माता। पृथिवी। दुःऽमतौ। धात्। उरौ। देवाः। अनिःऽबाधे। स्याम। सं। अ
श्विनोः। अवसा। नूतनेन। मयःऽभुवा। सुऽप्रनीती। गमेम। आ। नः। रयिं। वहतं। आ। उत
वीरान्। आ। विश्वानि। अमृता। सौभगानि। १९। आ। धेनवः। पयसा। तूर्णिःऽअर्थाः। अ
मर्धंतीः। उप। नः। यंतु। मध्वा। महः। राये। बृहतीः। सप्त। विप्रः। मयःऽभुवः। जरिता। जोहवी
ति। आ। सुऽस्तुती। नमसा। वर्तयध्यै। द्यावा। वाजाय। पृथिवी इति। अमृध्रे इति। पिता। मा
ता। मधुऽवचाः। सुऽहस्ता। भरेऽभरे। नः। यशसौ। अविष्टां। अध्वर्यवः। चकृऽवांसः। म

© Dharmartha Trust J&K. Digitized by eGangotri

प॰व॰ धन्व । प्र । वः । भरत । चारु । शुष्मं । होता ऽइव । नः । प्रथमः । पाहि । अस्य । देव । मध्वः । ररिम । ते ।
२९ मदाय । दश । क्षिपः । युञ्जते । बाहू इति । अद्रिं । सोमस्य । या । शमितारा । सुऽहस्ता । मध्वः । रसं ।
भ सुऽगभस्तिः । गिरिऽस्थां । चनिश्चदत् । दुदुहे । शुक्रं । अंशुः । असौ । वि । ते । जुजुषाणाय । सोमः । क्र
29 त्वे । दक्षाय । बृहते । मदाय । हरी इति । रथे । सुऽधुरा । योगे । अर्वाक् । इन्द्र । प्रिया । कृणुहि । हूयमा
नः । आ । नः । मही । अरमतिं । सऽजोषाः । ग्नां । देवीं । नमसा । रातऽहव्यां । मधोः । मदाय ।
बृहतीं । ऋतऽज्ञां । आ । अग्ने । वह । पथिऽभिः । देवऽयानैः । अंजन्ति । यं । प्रथयन्तः । न । विप्राः । व
पाऽवन्तं । न । अग्निना । तपन्तः । पितुः । न । पुत्रः । उपसि । प्रेष्ठः । आ । घर्मः । अग्निं । ऋतयन् । असा २९

© Dharmartha Trust J&K. Digitized by eGangotri

दि। अछ। मही। बृहती। शंऽतमा। गीः। दूतः। न। गंतु। अश्विना। हुवध्यै। मयःऽभुवा। सऽर

थौ। आ। यातं। अर्वाक्। गंतं। निऽधिं। धुरं। आणिः। न। नाभिं। प्र। तव्यसः। नमःऽउक्तिं। तु

रस्य। अहं। पूष्णः। उत। वायोः। अदिक्षि। या। राधसा। चोदितारा। मतीनां। या। वाजस्य।

द्रविणःऽदौ। उत। त्मन्। आ। नामऽभिः। मरुतः। वक्षि। विश्वान्। आ। रूपेभिः। जातऽवे

दः। हुवानः। यज्ञं। गिरः। जरितुः। सुऽस्तुतिं। च। विश्वे। गंत। मरुतः। विश्वे। ऊती॥ २३॥

आ। नः। दिवः। बृहतः। पर्वतात्। आ। सरस्वती। यजता। गंतु। यज्ञं। हवं। देवी। जुजुषाणा

। घृताची। शग्मां। नः। वाचं। उशती। शृणोतु। आ। वेधसं। नीलऽपृष्ठं। बृहंतं। बृहस्पतिं।

© Dharmartha Trust J&K. Digitized by eGangotri

प. ष. सद्ने । सादय । धां । सादतऽयोनिं । दमे । आ । दीदिऽवांसं । हिरण्यऽवर्णं । अरुषं । सपेम । आ । धर्ण
३० सिः । बृहन्ऽदिवः । ररराणः । विश्वेभिः । गंतु । ओमऽभिः । हुवानः । ग्नाः । वसानः । ओषधीः । अ
मृध्रः । त्रिऽधातुऽशृंगः । वृषभः । वयःऽधाः । ० मुक्षो । आ । योः । विपन्यवः । रास्पिरासः । अग्मन् ।
30 सुऽशेव्यं । नमसा । रातऽहव्याः । शिशुं । मृजंति । आयवः । ना । वासो । बृहता । वयः । बृहते । तुभ्यं ।
अग्ने । धिया । असुरः । मिथुनासः । सचंत । ० ॥ २२ ॥ ते । प्रत्नऽथा । पूर्वऽथा ॥ विश्वऽथा । इमऽथा ।
ज्येष्ठऽतातिं । बर्हिऽसदं । स्वःऽविदं । प्रतीचीनं । वृजनं । दोहसे । गिरा । आशुं । जयंतं । अनु ।
अनु । यासु । वर्धसे । श्रियः । सुऽदृशीः । उपरस्याः । याः । स्वः । विऽरोचमानः । ककुभां । अचो ३०

© Dharmartha Trust J&K. Digitized by eGangotri

दैते। सुऽगोपाः। असि। नादभाया। सुक्रतो इति सुऽक्रतो। पुरः। मायाभिः। क्रतो। आसा। नाम।
ते। असै। हविः। सचते। सत्। च। धातु। च। अरिष्टऽगातुः। सः। होता। सहःऽभारः। प्रऽस
र्पिणः। अनु। बर्हिः। रवा। शिशुः। मध्ये। युवा। अजरः। विऽस्रुहा। हितः। प्र। वः। एतु। सु
युजः। यामन्। इष्टये। नीचीः। अमुष्मै। यम्यः। ऋतऽवृधः। सुयन्तुऽभिः। सर्वऽशासैः। अभी
शुऽभिः। क्रिविः। नामानि। प्रवणे। मुषायति। सं। जम्भुः। राणः। तरुऽभिः। सुतेऽगृभं। वया
किनं। चित्तऽगर्भासु। सुस्वरुः। धारऽवाके। ऋजुऽगाथ। शोभसे। वर्धस्व। पत्नीः।
अभि। जीवः। अध्वरे। रशा। याद्दक्। एना। ददृशे। ताद्दक्। उच्यते। सं। छायया। दधिरे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ सिध्रया। अपऽस्तु। आ। मही। अस्मभ्यं। उरुऽसा। उरु। ज्रयः। बृहत्। सुऽवीरं। अनपऽच्युतं।
३१ सहः। वेत्ति। आ। गुः। जनिऽवान्। वै। अति। स्पृधः। सुऽमर्यता। मनसा। सूर्यः। कविः। घ्रं
सं। रक्षंतं। परि। विश्वतः। गयं। अस्माकं। शर्म। वनवत्। स्वऽवसुः। ज्या। यांसे। अस्य। य
31 तुनस्य। केतुना। ऋषिऽस्वरं। चरति। या। सु। नाम। ते। या। दृशिमन्। धायि। तं। अपस्यया।
विदत्। यः। ऊं इति। स्वयं। वहते। सः। अरं। करत्। समुद्रं। आ। सां। अवात्। स्थे। अग्निं। आ।
ना। रिष्यति। सवनं। यस्मिन्। आऽयता। अग्नौ। ना। हार्दि। क्रवणस्य। रेजते। यत्र। मतिः।
विद्यते। पूतऽबंधनी। सः। हि। क्षत्रस्य। मनस्य। से। चित्तिऽभिः। एवऽवदस्य। यजत ३३

© Dharmartha Trust J&K. Digitized by eGangotri

स्या। सधैः। अवऽस्मारस्या। स्पृणवा। मा। रण्वऽभिः। शाविष्ठं। वाजं। विदुषा। चित्। अध्यैं॥ ॥ श्या
श्येनः। आसां। अदितिः। कक्ष्यः। मदः। विश्वऽवारस्य। यजतस्य। मायिनः। सं। अन्यंऽअन्यं। अ
र्थयंति। एतवै। विदुः। विऽसानं। परिऽपानं। अंति। ते। सदाऽपृणः। यजतः। वि। द्विषः। वधीत्।
बाहुऽवृक्तः। श्रुतऽवित्। तर्यः। वः। सचा। उभा। सः। वरा। प्रति। एति। भाति। च। आयतन्। ईं। गृणां। मज
ने। सुप्रयावऽभिः। सुतंऽभरः। यजमानस्य। सत्ऽपतिः। विश्वासां। ऊधः। सः। धियां। उत्ऽअं
चनः। भरत्। धेनुः। रसऽवत्। शिश्रिये। पयः। अनुऽब्रुवाणः। अधि। [illegible] एति। न। स्वपन्। यः।
जागार। तं। ऋचः। कामयंते। यः। जागार। तं। ऊं इति। सामानि। यंति। यः। जागार। तं। अयं। सो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰व॰ मः। आ। हा। तव। अहं। अस्मि। सख्ये। नि॑ऽओकाः। अग्निः। ना। गा। रा। ०॥ २५॥ विदाः। दिवः। वि॑ऽस्यन्।
३२ अद्रिं। उक्थैः। आ॑ऽयत्याः। उषसः। अर्चिनः। गुः। अप। अवृतं। व्रजिनीः। उत्। स्वः। गात्। विदुः। मा
32 नुषीः। देवः। आ। वरिस्यां। वः। वि। स्रर्यः। अमतिं। न। श्रियं। सात्। आ। ऊर्वात्। गवां। माता। जानती।
गात्। धन्व॑ऽअर्णसः। नद्यः। खादः॑ऽअर्णाः। स्थूणा॑ऽइव। सुऽमिता। दृंहत। द्यौः। अस्मे। उक्थाय।
पर्वतस्य। गर्भः। महीनां। जनुषे। पूर्व्याय। वि। पर्वतः। जिहीत। साधत। द्यौः। आ॑ऽविवासंतः।
दस्मयंत। भूम। सुऽउक्तेभिः। वः। वचः॑ऽभिः। देव॑ऽजुष्टैः। इंद्रा। नु। अग्नी इति। अवसे। हुवध्यै।
उक्थेभिः। हि। स्म। कवयः। सुऽयज्ञाः। आ॑ऽविवासंतः। मरुतः। यजंति। एता। इति। नु। अद्य। सु राम ३२

© Dharmartha Trust J&K. Digitized by eGangotri

ध्मः। भवाम। प्र। दुच्छुनाः। मिनवाम। वरीयः। आरे। द्वेषांसि। सनुतः। दधाम। अयाम। प्रांचः।
यजमानं। अच्छ॥ एत। आ। इत। धियं। कृणवाम। सखायः। अप। या। माता। ऋणुत। व्रजं। गोः।
यया। मनुः। विशिऽशिप्रं। जिगाय। यया। वणिक्। वंकुः। आप। पुरीषं। अनूनोत्। अत्र। ह
स्तऽयतः। अद्रिः। आर्चन्। येन। दश। मासः। नवऽग्वाः। ऋतं। यती। सरमा। गाः। अविंदत्।
विश्वानि। सत्या। अंगिराः। चकार। विश्वे। अस्याः। विऽउषि। माहिनायाः। सं। यत्। गोभिः। अंगि
रसः। नवंत। उस्राः। आ। सां। परमे। सधऽस्थे। ऋतस्य। पथा। सरमा। विदत्। गाः। आ। सूर्यः।
यातु। सप्तऽअश्वः। क्षेत्रं। यत्। अस्य। उर्विया। दीर्घऽयाथे। रघुः। श्येनः। पतयत्। अंधः। अच्छ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ युवा । कविः । दीदयत् । गोषु । गच्छन् ॥ आ । सूर्यः । अरुहत् । शुक्रं । अर्णः । अयुक्त । यत् । हरितः । वी
३३ तऽपृष्ठाः । उद्ना । न । नावं । अनयंत । धीराः । आऽशृण्वतीः । आपः । अर्वाक् । अतिष्ठन् ॥ धियं ।
वः । अपऽसु । दधिषे । स्वःऽसां । यया । अतरन् । दश । मासः । नवऽग्वाः । अया । धिया । स्याम ।
देवऽगोपाः । अया । धिया । तुतुर्याम । अति । अंहः ॥ २७ ॥ हयः । न । विद्वान् । अयुजि । स्वयं ।
धुरि । तां । वहामि । प्रऽतरणीं । अवस्युवं । न । अस्याः । वश्मि । विऽमुचं । न । आऽवृतं । पुनः ।
विद्वान् । पथः । पुरःऽएता । ऋजु । नेषति ॥ अग्ने । इंद्र । वरुण । मित्र । देवाः । शर्धः । प्र । यंत ।
मारुत । उत । विष्णो इति । उभा । नासत्या । रुद्रः । अध । ग्नाः । पूषा । भगः । सरस्वती । जुषंत ॥ ३३

© Dharmartha Trust J&K. Digitized by eGangotri

इन्द्राग्नी इति । मित्रावरुणा । अदितिं । स्वः । इति स्वः । पृथिवीं । द्यां । मरुतः । पर्वतान् । अपः । हुवे । वि
ष्णुं । पूषणं । ब्रह्मणः । पतिं । भगं । नु । शंसं । सवितारं । ऊतये । उत । नः । विष्णुः । उत । वातः । नः । अस्रि
धः । द्रविणःऽदाः । उत । सोमः । मयः । करत् । उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा ।
उत । विऽभ्वा । अनु । मंसते । उत । त्यत् । नः । मारुतं । शर्धः । आ । गमत् । दिविऽक्षयं । यजतं । बर्हिः ।
आऽसदे । बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यं । वरुणः । मित्रः । अर्यमा । उत । त्ये । नः ।
पर्वतासः । सुऽशस्तयः । सुऽदीतयः । नद्यः । त्रामणे । भुवन् । भगः । विऽभक्ता । शवसा । अवसा ।
आ । गमत् । उरुऽव्यचाः । अदितिः । श्रोतु । मे । हवं । देवानां । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवं

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. तु। नः। तुजे। यो। वाजेऽस्ना। नसे। याः। पार्थिवासः। याः। अपां। अपि। व्रते। ताः। नः। देवीः। सुऽहृ
३६ वाः। शर्म। यच्छत। उत। ग्नाः। व्यंतु। देवऽपत्नीः। इंद्राणी। अग्नायी। अश्विनी। राट्। आ। रोद
सी इति। वरुणानी। शृणोतु। व्यंतु। देवीः। यः। ऋतुः। जनीनां। २९। इति चतुर्थाष्टके द्विती
34 योध्यायः॥ ॥हरिः ओम्॥ प्रयुंजती सप्तप्रतिरथः कद्रु पंचप्रतिभानुजो गतं देवं वः प्रति
प्रभोः स्यात् रणपाणिर्विश्व स्वस्यात्रेयः पंक्त्यं तं नमग्ने पंचोना चतुर्थ्यैंद्रवाय वीरायत्यैकें
द्रवाय व्यैचतं सो। गायत्र्यः ष कु ष्विहति स्त्रोजगत्यं स्त्रिष्टुभो वांत्ये अनुष्टुभोः श्यावा
श्वस्यूनां श्यावाश्वा मारुतं हनं पंक्तिः षष्ठ्यं त्ये चेको वेदषाकशाकरूपव्बहत्यनुष्टुप्पुरउ ३६
© Dharmartha Trust J&K. Digitized by eGangotri

विङ्कृककुप्सतोबृहत्यौगायत्रीसतोबृहतीककुभौगायत्रीसतोबृहत्यौककुप्सतोबृहती
प्रशार्द्धायपंचोनाजागतमुपांसात्रिष्टुप्‌अग्नयज्यवोदशांत्सात्रिष्टुब्‌अग्नेनवबार्हतंतृतीयास
मन्योसतोबृहत्यावारुद्धासोष्टौद्वित्रिष्टुबंतंतमुप्रवस्त्रिष्टुबंतमीकेद्विजगत्संतमाग्नेयचबा
केष्वेकोनागायत्र्यैश्यावाश्वोत्रवेददश्चीनरंतपुरुमीळ्हौदाभ्यंरथवीतिमरुतश्चदानतुष्टत्र
राशंसंबुध्याचतरंतमहिषीशशीयसीपंचम्यनुष्टुप्नवमीसतोबृहत्येतेनवश्रुतविन्मैत्राव
रुणंवैनतं॥हरिःॐ॥प्रयुंजती।दिवः।एति।ब्रुवाणा।मही।माता।दुहितुः।बोधयंती।आऽवि
वासंती।युवतिः।मनीषा।पितृभ्यः।आ।सदने।जोहुवाना।आजिरासः।तनूः।अपः।ईयमानाः।आ

© Dharmartha Trust J&K. Digitized by eGangotri

[यंति।]

प.च. तस्थिऽवांसः। अमृतस्य। नाभिं। अनंता। उरवः। विश्वतः। सीं। परि। द्यावा। पृथिवी इति। पंथाः।
३५ उक्षा। समुद्रः। अरुषः। सुऽपर्णः। पूर्वस्य। योनिं। पितुः। आ। विवेश। मध्ये। दिवः। निऽहितः। पृश्निः।
35 अश्मा। वि। चक्रमे। रजसः। पाति। अंतौ। चत्वारः। ईं। बिभ्रति। क्षेमऽयंतः। दश। गर्भं। चरसे। धापयं
ते। त्रिऽधातवः। परमाः। अस्य। गावः। दिवः। चरंति। परि। सद्यः। अंतान्। इदं। वपुः। निऽवचनं। जना
सः। चरंति। यत्। नद्यः। तस्थुः। आपः। द्वे इति। यत्। ईं। बिभृतः। मातुः। अन्ये इति। इहऽइह। जाते इति। य
म्या। सबंधू इति सऽबंधू। आ। वितन्वाते। धियः। अस्मै। अप्यांसि। वस्त्रा। पुत्राय। मातरः। वयंति। उप
ऽप्रक्षे। वृषणः। मोदमानाः। दिवः। पथा। वध्वः। यंति। अच्छ। तत्। नु। अस्तु। मित्रावरुणा। तत्। नः। अग्ने। शं। ३५

© Dharmartha Trust J&K. Digitized by eGangotri

योः। अस्मभ्यं। इदं। अस्तु। शस्तं। अशीमहि। गाधं। उत। प्रतिऽस्थां। नमः। दिवे। बृहते। सदनाय॥ ७॥
कत्। ऊं इति। प्रियाय। धाम्ने। मनामहे। स्वऽक्षत्राय। स्वऽयशसे। महे। वयं। आऽमेन्यस्य। रजसः।
यत्। अभ्रे। आ। अपः। वृणाना। विऽतनोति। मायिनी। ताः। अत्नत। वयुनं। वीरऽवक्षणं। समान्या।
वृतया। विश्वं। आ। रजः। अपो इति। अपाचीः। अपराः। अप। ईजते। प्र। पूर्वाभिः। तिरते। दे
वऽयुः। जनः। आ। ग्रावऽभिः। अहन्येभिः। अक्तुऽभिः। वरिष्ठं। वज्रं। आ। जिघर्ति। मायिनि। शतं। वा। य
स्य। प्रऽचरन्। स्वे। दमे। संऽवर्तयन्तः। वि। च। वर्तयन्। अहा। तां। अस्य। रीतिं। परशोःऽइव। प्रति। अनी
कं। अख्यं। भुजे। अस्य। वर्पसः। सचा। यदि। पितुमन्तंऽइव। क्षयं। रत्नं। दधाति। भरऽहूतये। विशे। सः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ जिह्वया। चतुःऽअनीकः। ऋंजते। चारु। वसानः। वरुणः। यतन्। अरिं। न। तस्य। विद्म। पुरुषत्व
३६ ता। वयं। यतः। भगः। सविता। दाति। वार्यं।। ५।। देवं। वः। अद्य। सवितारं। आ। ईषे। भगं। च। रत्नं। वि
ऽभजंतं। आयोः। आ। वां। नरा। पुरुऽभुजा। ववृत्यां। दिवेऽदिवे। चित्। अश्विना। सखिऽयन्। प्र
ति। प्रऽयानं। असुरस्य। विद्वान्। सुऽउक्तैः। देवं। सवितारं। दुवस्य। उप। ब्रुवीत। नमसा। विऽजानन्
ज्येष्ठं। च। रत्नं। विऽभजंतं। आयोः। अदत्रऽया। दयते। वार्याणि। पूषा। भगः। अदितिः। उस्रः। इंद्रः
। विष्णुः। वरुणः। मित्रः। अग्निः। अहानि। भद्रा। जनयंत। दस्माः। तत्। नः। अनर्वा। सविता। वरूथं।
तत्। सिंधवः। इषयंतः। अनु। ग्मन्। उप। यत्। वोचे। अध्वरस्य। होता। रायः। स्याम। पतयः। वाजऽ ३६
रत्नाः।

36

© Dharmartha Trust J&K. Digitized by eGangotri

रस्माः । प्र । ये । वसुऽभ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्तऽवाचः । अव । एतु । अभ्वं । कृ
णुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥ ३ ॥ विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यं । विश्वः
। रायः । इषुध्यति । द्युम्नं । वृणीत । पुष्यसे । ते । ते । देव । नेतः । ये । च । इमान् । अनुऽशसे । ते । राया । ते
हि । आऽपृचे । सचेमहि । सचथ्यैः । अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत । आ
रे । विश्वं । पथेऽस्थां । द्विषः । युयोतु । युयुविः । यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः । नृऽ
मनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता । एषः । ते । देव । नेत । रिति । रथःऽपतिः । शं । रयिः ।
शं । राये । शं । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥ ४ ॥ अग्ने । सुतस्य । पीतये ।

© Dharmartha Trust J&K. Digitized by eGangotri

प·ऋ· विश्वैः। ऊमेभिः। आ। गहि। देवेभिः। हव्यऽदातये ॥ ऋतऽधीतयः। आ। गत। सत्यऽधर्माणः। अध्वरं

३० । अग्नेः। पिबत। जिह्वया ॥ विप्रेभिः। विप्र। सन्त्य। प्रातर्यावऽभिः। आ। गहि। देवेभिः। सोमऽपी

तये ॥ अयं। सोमः। चमूऽइति। सुतः। अमत्रे। परि। सिच्यते। प्रियः। इंद्राय। वायवे। वायो इति

। आ। याहि। [illegible]। वीतये। जुषाणः। हव्यऽदातये। पिब। सुतस्य। अंधसः। अभि। प्रयः ।५।। ०

सुतानां। पीतिं। अर्हथः। तान्। जुषेथां। अरेपसौ। अभि। प्रयः ॥ सुताः। इंद्राय। वायवे। सोमा

सः। दधिऽआशिरः। निम्नं। न। यंति। सिंधवः। अभि। प्रयः ॥ सऽजूः। विश्वेभिः। देवेभिः। अश्वि

ऽभ्यां। उषसा। सऽजूः। आ। याहि। अग्ने। अत्रिऽवत्। सुते। रण ॥ सऽजूः। मित्रावरुणाभ्यां। सऽ ३०

37

© Dharmartha Trust J&K. Digitized by eGangotri

थि॰

नः। सोमेन। विष्णुना। ०। सऽजूः। आदित्यैः। वसुऽभिः। सऽजूः। इंद्रेण। वायुना। ०। द्या। स्वस्ति। नः।
मिमीतां। आश्विना। भगः। स्वस्ति। देवी। अदितिः। अनर्वणः। स्वस्ति। पूषा। असुरः। दधातु। नः।
स्वस्ति। द्यावा। पृथ्वी इति। सुऽचेतुना। स्वस्तये। वायुं। उप। ब्रवामहै। सोमं। स्वस्ति। भुवनस्य।
यः। पतिः। बृहस्पतिं। सर्वऽगणं। स्वस्तये। स्वस्तये। आदित्यासः। भवंतु। नः। विश्वे। देवाः। नः।
अद्य। स्वस्तये। वैश्वानरः। वसुः। अग्निः। स्वस्तये। देवाः। अवंतु। ऋभवः। स्वस्तये। स्वस्ति। नः।
रुद्रः। पातु। अंहसः। स्वस्ति। मित्रावरुणा। स्वस्ति। पथ्ये। रेवति। स्वस्ति। नः। इंद्रः। च। अग्निः।
च। स्वस्ति। नः। अदिते। कृधि। स्वस्ति। पंथां। अनु। चरेम। सूर्याचंद्रमसौऽइव। पुनः। ददता। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ये प्रेता।आ।नु।तान्।सं।गमेमहि॥७॥प्र।श्याव।ऽअश्व।धृष्णुऽया।अर्च।मरुत्ऽभिः।ऋक्वऽभिः।ये।अ
३९ द्रोघं।अनु।स्वधां।श्रवः।मदंति।यज्ञियाः॥ते।हि।स्थिरस्य।शवसः।सखायः।संति।धृष्णुऽ
या।ते।यामन्।आ।धृषत्ऽविनः।त्मना।पांति।शश्वतः॥ते।स्यंद्रासः।न।उक्षणः।अति।स्कं
दंति।शर्वरीः।मरुतां।अध।महः।दिवि।क्षमा।च।मन्महे॥मरुत्ऽसु।वः।दधीमहि।स्तोमं।य
ज्ञं।च।धृष्णुऽया।विश्वे।ये।मानुषा।युगा।पांति।मर्त्यं।रिषः॥अर्हंतः।ये।सुऽदानवः।नरः।
असामिऽशवसः।प्र।यज्ञं।यज्ञियेभ्यः।दिवः।अर्च।मरुत्ऽभ्यः॥५॥आ।रुक्मैः।आ।युधा।
नरः।ऋष्वाः।ऋष्टीः।असृक्षत।अनु।एनान्।अह।विऽद्युतः।मरुतः।जज्झतीःऽइव।भानुः। ३९

© Dharmartha Trust J&K. Digitized by eGangotri

अर्त।त्मना।दिवः।ये।ववृधंत।पार्थिवाः।ये।उरौ।अंतरिक्षे।आ।वृजने।वा।नदीनां।सधऽस्थे।
वा।महः।दिवः॥ शर्धः।मारुतं।उत्।शंस।सत्यऽशवसं।ऋभ्वसं।उत।स्म।ते।शुभे।नरः।प्रऽस्य
न्द्राः।युजत।त्मना।उत।स्म।ते।परुष्ण्यां।ऊर्णाः।वसत।शुंध्यवः।उत।पव्या।रथानां।अद्रिं।भिंद
ति।ओजसा।आ।पथयः।विऽपथयः।अंतःऽपथाः।अनुऽपथाः।एतेभिः।मह्यं।नामऽभिः।य
ज्ञं।विऽस्तारः।ओहते॥ता।अध।नरः।नि।ओहते।अध।निऽयुतः।ओहते।अध।पारावताः।
इति॥चित्रा।रूपाणि।दर्श्या।छंदःऽस्तुभः।कुभन्यवः।उत्सं।आ।कीरिणः।नृतुः।ते।मे।के।चि
त्।न।तायवः।ऊमाः।आसन्।दृशि।त्विषे।ये।ऋष्वाः।ऋष्टिऽविद्युतः।कवयः।संति।वेधसः।

© Dharmartha Trust J&K. Digitized by eGangotri

प. क. तं। ऋषे। मारुतं। गणं। नमस्य। रमय। गिरा। अच्छ। ऋषे। मारुतं। गणं। दाना। मित्रं। न। योषणा। दि-
३९ वः। वा। धृष्णवः। ओजसा। स्तुताः। धीभिः। इषण्यत। नु। मन्वानः। एषां। देवान्। अच्छ। न। वक्षणा।
39 दाना। सचेत। सूरिऽभिः। यामऽश्रुतेभिः। अंजिऽभिः। प्र। ये। मे। बंधुऽएषे। गां। वोचंत। सूरयः। पृश्निं।
वोचंत। मातरं। अध। पितरं। इष्मिणं। रुद्रं। वोचंत। शिक्वसः। सप्त। मे। सप्त। शाकिनः। एकं। एका। श-
ता। ददुः। यमुनायां। अधि। श्रुतं। उत्। राधः। गव्यं। मृजे। नि। राधः। अश्व्यं। मृजे। ॥३०॥ कः। वेद। जानं।
एषां। कः। वा। पुरा। सुम्नेषु। आस। मरुतां। यत्। युयुज्रे। किलास्यः। आ। एतान्। रथेषु। तस्थुषः। कः।
शुश्राव। कथा। ययुः। कस्मै। सस्रुः। सुऽदासे। अनु। आपयः। इळाभिः। वृष्टयः। सह। ते। मे। आहुः। ३९

© Dharmartha Trust J&K. Digitized by eGangotri

ये।आऽग्यऽयुः।उप।सुऽभिः।विऽभिः।मदे।नरः।मर्याः।अरेपसः।इमान्।पश्यन्।इति।स्तुहि।ये।अं
जिषु।ये।वाशीषु।स्वऽभानवः।स्रक्षु।रुक्मेषु।खादिषु।श्रायाः।रथेषु।धन्वऽसु।युष्माकं।स्म
।रथान्।अनु।मुदे।दधे।मरुतः।जीरऽदानवः।वृष्टी।द्यावः।यतीःऽइव।।११।।आ।यं।नरः।सुऽदा
नवः।ददाशुषे।दिवः।कोशं।अचुच्यवुः।वि।पर्जन्यं।सृजंति।रोदसीइति।अनु।धन्वना।यंति।
वृष्टयः।ततृदानाः।सिंधवः।क्षोदसा।रजः।प्र।सस्रुः।धेनवः।यथा।स्यन्नाः।अश्वाःऽइव।अध्व
नः।विऽमोचने।वि।यत्।वर्तंते।एन्यः।आ।यात।मरुतः।दिवः।आ।अंतरिक्षात्।अमात्।उत।
मा।अव।स्थात।पराऽवतः।मा।वः।रसा।अनिभा।कुभा।क्रुमुः।मा।वः।सिंधुः।नि।रीरमत्।मा।

त

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ यः। परि। स्थातन। सरयुः। पुरीषिणी। अस्मे इति। इत्। सुम्नं। अस्तु। वः। तं। वः। शर्धं। रथानां। त्वेषं।
५० गणं। मारुतं। नव्यसीनां। अनु। प्र। यंति। वृष्टयः। शर्धंऽशर्धं। वः। एषां। व्रातंऽव्रातं। गणंऽग-
५० णं। सुशस्तिऽभिः। अनु। क्रामेम। धीतिऽभिः। कस्मै। अद्य। सुऽजाताय। रातऽहव्याय। प्र। ययुः।
एना। यामेन। मरुतः। येन। तोकाय। तनयाय। धान्यं। बीजं। वहध्वे। अक्षितं। अस्मभ्यं। त-
त्। धत्तन। यत्। वः। ईमहे। राधः। विश्वऽआयु। सौभगं। अति। इयाम। निदः। तिरः। स्वस्तिऽभि-
ः। हित्वा। अवद्यं। अरातीः। वृष्ट्वी। शं। योः। आपः। उस्रि। भेषजं। स्याम। मरुतः। सह। सुऽदेवः।
सऽमह। असति। सुऽवीरः। नरः। मरुतः। सः। मर्त्यः। यं। त्रायध्वे। स्याम। ते। तो। स्तुहि। भोजा ५०

© Dharmartha Trust J&K. Digitized by eGangotri

न्।स्तुवतः। अस्य। यामनि। रणन्। गावः। न। यवसे। यतः। पूर्वान्ऽइव। सखीन्। अनु। ह्वय। गिरा। गृ

णीहि। कामिनः॥१६॥३॥ प्र। शर्धाय। मारुताय। स्वऽभानवे। इमां। वाचं। अनज। पर्वतऽच्युते। घ

र्मऽस्तुभे। दिवः। आ। पृष्ठऽयज्वने। द्युम्नऽश्रवसे। महि। नृम्णं। अर्चत। प्र। वः। मरुतः। तविषाः। उदन्य

वः। वयःऽवृधः। अश्वऽयुजः। परिऽज्रयः। सं। विऽद्युता। दधति। वाशति। त्रितः। स्वरंति। आपः। अवना।

परिऽज्रयः। विद्युत्ऽमहसः। नरः। अश्मऽदिद्यवः। वातऽत्विषः। मरुतः। पर्वतऽच्युतः। अब्दऽया। चित्।

मुहुः। आ। ह्रादुनिऽवृतः। स्तनयत्ऽअमाः। रभसाः। उत्ऽओजसः। वि। अक्तून्। रुद्राः। वि। अहानि। शि हा

क्वसः। वि। अंतरिक्षं। वि। रजांसि। धूतयः। वि। यत्। अज्रान्। अजथ। नावः। ईं। यथा। वि। दुःऽगानि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चं॰ मरुतः । न । अह । रिष्यथ । तत् । वीर्यं । वः । मरुतः । महिऽत्वनं । दीर्घं । ततान । सूर्यः । न । योजनं । एताः ।

५१ न । यामे । अगृभीतऽशोचिषः । अनश्वऽदां । यत् । नि । अयातन । गिरिं ॥ १४ ॥ अभ्राजि । शर्धः । मरु

तः । यत् । अर्णसं । मोषथ । वृक्षं । कपनाऽइव । वेधसः । अध । स्म । नः । अरमतिं । सऽजोषसः । चक्षुःऽ

इव । यंत । अनु । नेषथ । सुऽगं । न । सः । जीयते । मरुतः । न । हन्यते । न । स्रेधति । न । व्यथते । न । रिष्य

ति । न । अस्य । रायः । उप । दस्यंति । न । ऊतयः । ऋषिं । वा । यं । राजानं । वा । सुसूदथ । नियुत्वंतः । ग्रा

मऽजितः । यथा । नरः । अर्यमणः । न । मरुतः । कबंधिनः । पिन्वंति । उत्सं । यत् । इनासः । अस्वरन् । वि ।

उंदंति । पृथिवीं । मध्वः । अंधसा । प्रवत्ऽवती । इयं । पृथिवी । मरुत्ऽभ्यः । प्रवत्ऽवती । द्यौः । भवति । प्रयत्ऽ ५१

वं

© Dharmartha Trust J&K. Digitized by eGangotri

प्यः। प्रवत्वतीः। पथ्याः। अंतरिक्ष्याः। प्रवत्वंतः। पर्वताः। जीरऽदानवः। यत्। मरुतः। सऽभरसः। स्वःऽन
रः। सूर्ये। उत्ऽइते। मदथ। दिवः। नरः। न। वः। अश्वाः। श्रथयंत। अह। सिस्रतः। सद्यः। अस्य। अध्व
नः। पारं। अश्नुथ॥१०॥ अंसेषु। वः। ऋष्टयः। पत्ऽसु। खादयः। वक्षःऽसु। रुक्माः। मरुतः। रथे। शु
भः। अग्निऽभ्राजसः। विऽद्युतः। गभस्त्योः। शिप्राः। शीर्षऽसु। विऽतताः। हिरण्ययीः। तं। नाकं। अ
र्यः। अगृभीतऽशोचिषं। रुशत्। पिप्पलं। मरुतः। वि। धूनुथ। सं। अच्यंत। वृजना। अतित्विषंत। य
त्। स्वरंति। घोषं। विऽततं। ऋतऽयवः। युष्माऽदत्तस्य। मरुतः। विऽचेतसः। रायः। स्याम। रथ्यः। व
यस्वतः। न। यः। युच्छति। तिष्यः। यथा। दिवः। अस्मे इति। ररंत। मरुतः। सहस्रिणं। यूयं। रयिं। मरु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ पं॰ तः। स्याम। वीरं। यूयं। ऋषिं। अवथ। साम॑ऽविप्रं। यूयं। अर्वंतं। भरताय। वाजं। यूयं। धत्थ। राजानं।
५२ श्रुष्टिऽमंतं। तत्। वः। यामि। द्रविणं। सद्यःऽऊतयः। येन। स्वः। न। ततनाम। नॄन्। अभि। इदं। सु। मे।
मरुतः। हर्यत। वचः। यस्य। तरेम। तरसा। शतं। हिमाः॥ १५॥ प्रऽयज्यवः। मरुतः। भ्राजत्ऽऋष्टयः।
बृहत्। वयः। दधिरे। रुक्मऽवक्षसः। ईयंते। अश्वैः। सुऽयमेभिः। आशुऽभिः। शुभं। यातां। अनु। रथाः।
अवृत्सत। स्वयं। दधिध्वे। तविषीं। यथा। विद। बृहत्। महांतः। उर्विया। वि। राजथ। उत। अंतरिक्षं।
ममिरे। वि। ओजसा॥ँ साकं। जाताः। सुऽभ्वः। साकं। उक्षिताः। श्रिये। चित्। आ। प्रऽतरं। ववृधुः।
नरः। विऽरोकिणः। सूर्यस्यऽइव। रश्मयः॥ ० आऽभूषेण्यं। वः। मरुतः। महिऽत्वनं। दिदृक्षेण्यं। ५२

© Dharmartha Trust J&K. Digitized by eGangotri

स्सूर्यस्यऽइव । चक्षणं । उतो इति । अस्मान् । अमृतऽत्वे । दधातन ।०। उत् । ईरयथ । मरुतः । समुद्रतः ।
यूयं । वृष्टिं । वर्षयथ । पुरीषिणः । न । वः । दस्राः । उप । दस्यंति । धेनवः ।०।।१०।। यत् । अश्वान् ।
धूःऽसु । पृषतीः । अयुग्ध्वं । हिरण्ययान् । प्रति । अत्कान् । अमुग्ध्वं । विश्वाः । इत् । स्पृधः । मरुतः ।
वि । अस्यथ ।०। न । पर्वताः । न । नद्यः । वरंत । वः । यत्र । अचिध्वं । मरुतः । गछथ । इत् । ऊं इति । तत् । उत । म
द्यावापृथिवी इति । याथन । परि ।०। यत् । पूर्व्यं । मरुतः । यत् । च । नूतनं । यत् । उद्यते । वसवः । यत्
। च । शस्यते । विश्वस्य । तस्य । भवथ । नवेदसः ।०। मृळत । नः । मरुतः । मा । वधिष्टन । अस्मभ्यं ।
शर्म । बहुलं । वि । यंतन । अधि । स्तोत्रस्य । सख्यस्य । गातन ।०। यूयं । अस्मान् । नयत । वस्यः । अ

© Dharmartha Trust J&K. Digitized by eGangotri

प.व. च्छ।निः।अंहतिऽभ्यः।मरुतः।गृणानाः।जुषध्वं।नः।हव्यऽदातिं।यजत्राः॥१०॥३८॥अग्ने।शर्धन्तं।आ।
४३ गणं।पिष्टं।रुक्मेभिः।अंजिऽभिः।विशः।अद्य।मरुतां।अव।ह्वये।१।यथा।चित्।मन्यसे।हृदा।तत्।
इत्।मे।जग्मुः।आऽशसः।ये।ते।नेदिष्ठं।हवनानि।आऽगमन्।तान्।वर्ध।भीमऽसंदृशः।मीळ्हु
ष्मतीऽइव।पृथिवी।पराऽहता।मदंती।एति।अस्मत्।आ।ऋक्षः।न।वः।मरुतः।शिमीऽवान्।अ
मः।दुध्रः।गौःऽइव।भीमऽयुः।नि।ये।रिणंति।ओजसा।रथा।गावः।न।दुःऽधुरः।०।पर्वतं।गिरिं।
०उत्।तिष्ठ।नूनं।एषां।स्तोमैः।संऽउक्षितानां।मरुतां।पुरुऽतमं।अपूर्व्यं।गवां।सर्गंऽइव।ह्व
ये॥५॥युंग्ध्वं।०युंग्ध्वं।रथेषु।रोहितः।युंग्ध्वं।हरीऽइति।अजिरा।धुरि।वोळ्हवे।वहिष्ठा।धु ४३

© Dharmartha Trust J&K. Digitized by eGangotri

रि। वो॥ ६ वे३ उत। स्यः। वाजी। अरुषः। तुविऽस्वनिः। इह। स्म। धायि। दर्शतः। मा। वः। यामेषु। मरु
तः। चिरं। करत्। प्र। तं। रथेषु। चोदत। रथं। नु। मारुतं। वयं। श्रवस्युं। आ। हुवामहे। आ। यस्मिन्।
तस्थौ। सुऽरणानि। बिभ्रती। सचा। मरुत्ऽसु। रोदसी। तं। वः। शर्धं। रथेऽशुभं। त्वेषं। पनस्युं।
आ। हुवे। यस्मिन्। सुऽजाता। सुऽभगा। महीयते। सचा। मरुत्ऽसु। मीळ्हुषी॥ २०॥ आ। रुद्रा
सः। इंद्रऽवंतः। सऽजोषसः। हिरण्यऽरथाः। सुविताय। गंतन। इयं। वः। अस्मत्। प्रति। हर्यते। म
तिः। तृष्णऽजे। न। दिवः। उत्साः। उदन्यवे। वाशीऽमंतः। ऋष्टिऽमंतः। मनीषिणः। सुऽधन्वानः। इ
षुऽमंतः। निषंगिणः। सुऽअश्वाः। स्थ। सुऽरथाः। पृश्निऽमातरः। [illegible] सुऽआयुधाः। मरुतः। या

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ धन्व । शुभं । धूनुथ । यां । पर्वतान् । दाशुषे । वसु । नि । वः । वना । जिहते । यामनः । भिया । कोपयथ ।
५५ पृथिवीं । पृश्निऽमातरः । शुभे । यत् । उग्राः । पृषतीः । अयुग्ध्वं । वातऽत्विषः । मरुतः । वर्षऽनिर्णि
ग जः । यमाःऽइव । सुऽसदृशः । सुऽपेशसः । पिशंगऽअश्वाः । अरुणऽअश्वाः । अरेपसः । प्रऽत्वक्षसः
44 । महिना । द्यौःऽइव । उरवः । पुरुऽद्रप्साः । अंजिऽमंतः । सुऽदानवः । त्वेषऽसंदृशः । अनवभ्रऽरा
धसः । सुऽजातासः । जनुषा । रुक्मऽवक्षसः । दिवः । अर्काः । अमृतं । नाम । भेजिरे ॥ ५ ॥ ऋष्
टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलं । हितं । नृम्णा । शीर्षऽसु । आ
युधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे । गोऽमत् । अश्वऽवत् । रथऽवत् । सु ५५

© Dharmartha Trust J&K. Digitized by eGangotri

वीरं। चंद्रऽवत्। राधः। मरुतः। ददात। नः। प्रऽशस्तिं। नः। कृणुत। रुद्रियासः। भक्षीय। वः। अवसः। दैव्य
स्य। हये। नरः। मरुतः। मृळत। नः। तुविऽमघासः। अमृताः। ऋतऽज्ञाः। सत्यऽश्रुतः। कवयः। युवा
नः। बृहत्ऽगिरयः। बृहत्। उक्षमाणाः॥ २२ ॥ तं। ऊं इति। नूनं। तविषीऽमंतं। एषां। स्तुषे। गणं। मा
रुतं। नव्यसीनां। ये। आशुऽअश्वाः। अमऽवत्। वहंते। उत। ईशिरे। अमृतस्य। स्वऽराजः। त्वेषं।
गणं। तवसं। खादिऽहस्तं। धुनिऽव्रतं। मायिनं। दातिऽवारं। मयःऽभुवः। ये। अमिताः। महिऽ
त्वा। वंदस्व। विप्र। तुविऽराधसः। नॄन्। आ। वः। यंतु। उदऽवाहासः। अद्य। वृष्टिं। ये। विश्वे। म
रुतः। जुनंति। अयं। यः। अग्निः। मरुतः। संऽइद्धः। एतं। जुषध्वं। कवयः। युवानः। यूयं। राजानं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ इयं।अस्य।नाय।विभ्व।तष्टं।जन।यथा।यज्ञाः।शुष्मन्।एति।शुष्टिऽहा।बाहुऽजूतः।शुष्मत्।सतः
५५ अश्वाः।मरुतः।सुऽवीरः।अराः।इवाइत्।अचरमाः।अहाऽइव।प्रऽप्रायन्।अकेवाः।महःऽ
भिः।पश्नैः।पुत्राः।उपऽमासः।रभिष्ठाः।स्वया।मत्या।मरुतः।सं।मिमिक्षुः।यत्।प्र।अयासि
ष्ट।पृषतीभिः।अश्वैः।वीळुपविऽभिः।मरुतः।रथेभिः।क्षोदंते।आपः।रिणते।वनानि।अव।
उस्त्रियः।वृषभः।क्रंदतु।द्यौः।प्रथिष्ट।यामन्।पृथिवी।चित्।एषां।भर्ताऽइव।गर्भं।स्वं।
इत्।शवः।धुः।वातान्।हि।अश्वान्।धुरि।आऽयुयुज्रे।वर्षं।स्वेदं।चक्रिरे।रुद्रियासः।१०
।रक्षा।प्र।वः।स्पर्धा।अक्रन्।सुविताय।दावने।अर्चा।दिवे।प्र।पृथिव्यै।ऋतं।भरे।उक्षंते।अ ५५

45

© Dharmartha Trust J&K. Digitized by eGangotri

श्वान्। तरुषंते। आ। रजः। अनु। स्वं। भानुं। श्रथयंते। अर्णवैः। अमात्। एषां। भियसा। भूमिः। एज
ति। नौः। न। पूर्णा। क्षरति। व्यथिः। यती। दूरेऽदृशः। ये। चितयंते। एमऽभिः। अंतः। महे। विदथे।
येतिरे। नरः। गवांऽइव। श्रियसे। शृंगं। उत्ऽतमं। सूर्यः। न। चक्षुः। रजसः। विऽसर्जने। अत्याःऽ
इव। सुऽभ्वः। चारवः। स्थन। मर्याःऽइव। श्रियसे। चेतथ। नरः। कः। वः। महांति। महतां। उत्। अ
श्नवत्। कः। काव्या। मरुतः। कः। ह। पौंस्या। यूयं। ह। भूमिं। किरणं। न। रेजथ। प्र। यत्। भरध्वे।
सुविताय। दावने। अश्वाःऽइव। इत्। अरुषासः। सऽबंधवः। शूराःऽइव। प्रऽयुधः। प्र। उत। युयुधुः।
मर्याःऽइव। सुऽवृधः। ववृधुः। नरः। सूर्यस्य। चक्षुः। प्र। मिनंति। वृष्टिऽभिः। ते। अज्येष्ठाः। अकनि

© Dharmartha Trust J&K. Digitized by eGangotri

१.च. ष्ठासः। उत्ऽभिदः। अमध्यमासः। महसा। वि। ववृधुः। सुऽजातासः। जनुषा। पृश्निऽमातरः। दिवः

४६ मर्याः। आ। नः। अच्छ। जिगातन। वयः। न। ये। श्रेणीः। पप्तुः। ओजसा। अंतान्। दिवः। बृहतः। सा

नुनः। परि। अश्वासः। एषां। उभये। यथा। विदुः। प्र। पर्वतस्य। नभनून्। अचुच्यवुः। मिमातु।

त द्यौः। अदितिः। वीतये। नः। सं। दानुऽचित्राः। उषसः। यतंतां। आ। अचुच्यवुः। दिव्यं। कोशं। एते।

ऋषे। रुद्रस्य। मरुतः। गृणानाः॥२४॥ ईळे। अग्निं। सुऽअवसं। नमःऽभिः। इह। प्रऽसत्तः। वि।

चयत्। कृतं। नः। रथैःऽइव। प्र। भरे। वाजयत्ऽभिः। प्रऽदक्षिणित्। मरुतां। स्तोमं। ऋध्यां। आ।

ये। तस्थुः। पृषतीषु। श्रुतासु। सुऽखेषु। रुद्राः। मरुतः। रथेषु। वना। चित्। उग्राः। जिहते। नि। वः। ४८

46

© Dharmartha Trust J&K. Digitized by eGangotri

भिया। पृथिवी। चित्। रेजते। पर्वतः। चित्। पर्वतः। चित्। महि। वृद्धः। बिभाय। दिवः। चित्। सानु।
रेजत। स्वने। वः। यत्। क्रीळथ। मरुतः। ऋष्टिऽमन्तः। आपःऽइव। सध्र्यञ्चः। धवध्वे। वरःऽइव।
इत्। रैवतासः। हिरण्यैः। अभि। स्वधाभिः। तन्वः। पिपिश्रे। श्रिये। श्रेयांसः। तवसः। रथेषु।
सत्रा। महांसि। चक्रिरे। तनूषु। अज्येष्ठासः। अकनिष्ठासः। एते। सम्। भ्रातरः। ववृधुः। सौभगा
य। युवा। पिता। सुऽअपाः। रुद्रः। एषाम्। सुऽदुघा। पृश्निः। सुऽदिना। मरुत्ऽभ्यः। यत्। उत्ऽतमे।
भ मरुतः। मध्यमे। वा। यत्। वा। अवमे। सुऽभगासः। दिवि। स्थ। अतः। नः। रुद्राः। उत। वा। नु। अस्य।
अग्ने। वित्तात्। हविषः। यत्। यजाम। अग्निः। च। यत्। मरुतः। विश्वऽवेदसः। दिवः। वहध्वे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ५॰ उत्ऽतरात्।अधि।स्नुऽभिः।ते।मंदसानाः।धुनयः।रिशादसः।वामं।धत्त।यजमानाय।सुन्वते।
६० अग्ने।मरुत्ऽभिः।शुभयत्ऽभिः।ऋक्वऽभिः।सोमं।पिब।मंदसानः।गणश्रिऽभिः।पावकेभिः।
विश्वंऽइन्वेभिः।आयुऽभिः।वैश्वानर।प्रऽदिवा।केतुना।सऽजूः॥२५॥ के।स्थ।नरः।श्रेष्ठऽतमाः।
ये।एकःऽएकः।आऽयय।परमस्याः।पराऽवतः।क्व।वः।अश्वाः।क्व।अभीशवः।कथं।शेक।कथा।
यय।पृष्ठे।सदः।नसोः।यमः।जघने।चोदः।एषां।वि।सक्थानि।नरः।यमुः।पुत्रऽकृथे।न।ज
नयः।परा।वीरासः।इतन।मर्यासः।भद्रऽजानयः।अग्निऽतपः।यथा।असथ।सनत्।सा।
अश्व्यं।पशुं।उत।गव्यं।शतऽअवयं।श्यावाश्वऽस्तुताय।या।दोः।वीराय।उपऽबर्बृहत्॥२६॥ ५७

© Dharmartha Trust J&K: Digitized by eGangotri

उत। वा। स्त्री। शसीयसी। पुंसः। भवति। वस्यसी। अदेवऽत्रात्। अराधसः॥ वि। या। जानाति।
जसुरिं। वि। तृष्यंतं। वि। कामिनं। देवऽत्रा। कृणुते। मनः। उत। घ। नेमः। अस्तुतः। पुमान्। इ
ति। ब्रुवे। पणिः। सः। वैरऽदेये। इत्। समः। उत। मे। अरपत्। युवतिः। ममंदुषी। प्रति। श्यावाय
। वर्तनिं। वि। रोहिता। पुरुऽमीळ्हाय। येमतुः। विप्राय। दीर्घऽयशसे। यः। मे। धेनूनां। शतं। वैद
त्ऽअश्विः। यथा। ददत्। तरंतःऽइव। मंहना॥ २७॥ ये। ईं। वहंते। आशुऽभिः। पिबंतः। मदिरं।
मधु। अत्र। श्रवांसि। दधिरे। येषां॥ श्रिया। अधि। रोदसीइति। विऽभ्राजंते। रथेषु। आ। दिवि।
रुक्मःऽइव। उपरि। युवा। सः। मारुतः। गणः। त्वेषऽरथः। अनेद्यः। शुभंऽयावा। अप्रतिऽस्कुतः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ कः। वेद। नूनं। एषां। यत्र। मदंति। धूतयः। ऋतऽजाताः। अरेपसः। सूर्यं। मर्तः। विपन्यवः। प्रऽने

४८ तारः। इत्था। धिया। श्रोतारः। यामऽहूतिषु। १८। ते। नः। वसूनि। काम्या। पुरुऽचंद्राः। रिशाद

48 सः। आ। यज्ञियासः। ववृत्तन। एतं। मे। स्तोमं। ऊर्म्ये। दार्भ्याय। परा। वह। गिरः। देवि। रथी

ऽइव। उत। मे। वोचतात्। इति। सुतऽसोमे। रथऽवीतौ। न। कामः। अप। वेति। मे। एषः। क्षेति।

रथऽवीतिः। मघऽवा। गोऽमतीः। अनु। पर्वतेषु। अपऽश्रितः। १९। ऋतेन। ऋतं। अपिऽ

हितं। ध्रुवं। वां। सूर्यस्य। यत्र। विऽमुचंति। अश्वान्। दश। शता। सह। तस्थुः। तत्। एकं।

देवानां। श्रेष्ठं। वपुषां। अपश्यं। तत्। सु। वां। मित्रावरुणा। महिऽत्वं। ईर्मा। तस्थुषीः। अहऽ ४८

© Dharmartha Trust J&K. Digitized by eGangotri

भिः। दुदुहे। विश्वाः। पिन्वथः। स्वसरस्य। धेनाः। अनु। वां। एकः। पविः। आ। वर्तते। अधा

रयतं। पृथिवीं। उत। द्यां। मित्रराजाना। वरुणा। महःऽभिः। वर्धयतं। ओषधीः। पिन्वतं

तं। गाः। अव। वृष्टिं। सृजतं। जीरदानू इति जीरऽदानू। ०। सुऽयुजः। वहंतु। यतऽरश्म

यः। उप। यंतु। अर्वाक्। घृतस्य। निःऽनिक्। अनु। वर्तते। वां। उप। सिंधवः। प्रऽदिवि। क्षरंति। अ

नु। श्रुतां। अमतिं। वर्धत्। उर्वीं। बर्हिःऽइव। यजुषा। रक्षमाणा। नमस्वंता। धृतऽदक्षा। अधि। गर्ते।

मित्रा। आसाथे इति। वरुण। इळासु। अंतरिति॥ ५॥ अकविऽहस्ता। सुऽकृते। परःऽपा। यं। त्रा

साथे इति। वरुणा। इळासु। अंतरिति। राजाना। क्षत्रं। अहृणीयमाना। सहऽस्रऽस्थूणं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ बिभृथः। सहा द्वौ। हिरण्यऽनिर्निक्। अयः। अस्य। स्थूणा। वि। भ्राजते। दिवि। अश्वाजनीऽ
५९ इव। भद्रे। क्षेत्रे। निऽमिता। तिल्विले। वा। सनेम। मध्वः। अधिऽगर्त्यस्य। हिरण्यऽरूपं। उषसः।
विऽउष्टौ। अयःऽस्थूणं। उत्ऽइता। सूर्यस्य। आ। रोहथः। वरुण। मित्र। गर्तं। अतः। चक्षाथे इ
ति। अदितिं। दितिं। च। यत्नः। बंहिष्ठं। न। अतिःऽविधे। सुदानू इति सुऽदानू। अच्छिद्रं। शर्म। भुव
नस्य। गोपा। तेन। नः। मित्रावरुणौ। अविष्टं। सिसासन्तः। जिगीवांसः। स्याम॥ ३॥ इति
चतुर्थाष्टके तृतीयोध्यायः॥ ॥हरिः ॐ॥ ऋतस्य सप्तर्चं नाना जागतं वरुणं पं
क्त्यंतं तु पाः श्चैकेन पञ्चानहव्य आ चिकितानानुष्टुभं तु बाह्विक्स्था पंच यजतः प्रवो गायत्रं त्री ५९

© Dharmartha Trust J&K. Digitized by eGangotri

रोचनाचतुष्कंमरुच्चाक्षिःपुरूरुणागायत्रंबानस्त्वबाङ्कुत्वकंआमित्रऔक्षिहंयदद्यदशापौरआ
श्विनंतदात्रिष्टुभंतुकूष्ठःप्रानिन्नबावस्युःपांक्तंमाभानिपंचात्रिःप्रातर्यावाणाश्विनौनवंसप्त
वध्रिस्त्वष्टिगादिचतुर्थीत्रिष्टुप्पंचानुष्टुभौत्याःपंचगर्भस्त्राविष्ण्युपानिषन्महेदशसप्तस
वानुषस्यंतुपांक्तंघृतवामानंषड्युंजतेपंश्यावाश्वःसावित्रंतुजागतंनसविनुर्नेबगात्रमा च
वानुष्टुब्बृहद्दशात्रिःपार्जन्यमुपावास्तिस्तोजगत्स्युपांस्यानुष्टुब्बलिस्थात्रचंपार्थिवमानुष्टु
भंप्रसंमाजेषौवारुणंमिंत्रामन्नीषवैंद्राग्नंमानुष्टुभंविराट्पूर्वांतंप्रवोनवैयामरुत्वाह
तामलिजागतंबार्हस्पत्योभरद्वाजःषष्ठंमंडलमपश्यंसत्यंनसत्तोना॥ रणा॥ हरिः ॐ मू॥

© Dharmartha Trust J&K. Digitized by eGangotri

पृ॰ चे॰ ऋतस्य। गोपौ। अधि। तिष्ठथः। रथं। सत्यऽधर्माणा। परमे। विऽओमनि। यं। अत्र। मित्रावरुणा।
५० अवथः। युवं। तस्मै। वृष्टिः। मधुऽमत्। पिन्वते। दिवः। संऽराजौ। अस्य। भुवनस्य। राजथः। मि
त्रावरुणा। विदथे। स्वःऽदृशा। वृष्टिं। वां। राधः। अमृतऽत्वं। ईमहे। द्यावापृथिवी इति। वि। चरंति।
50 तन्यवः। संऽराजौ। उग्रा। वृषभा। दिवः। पती इति। पृथिव्याः। मित्रावरुणा। विचर्षणी इति विऽ
चर्षणी। चित्रेभिः। अभ्रैः। उप। तिष्ठथः। रवं। द्यां। वर्षयथः। असुरस्य। मायया। माया। वां। मि
त्रावरुणा। दिवि। श्रिता। सूर्यः। ज्योतिः। चरति। चित्रं। आयुधं। तं। अभ्रेण। वृष्ट्या। गूहथः।
दिवि। पर्जन्य। द्रप्साः। मधुऽमंतः। ईरते। रथं। युंजते। मरुतः। शुभे। सुऽखं। शूरः। न। मित्राव ५०

© Dharmartha Trust J&K. Digitized by eGangotri

रुणा। गोऽइति। पुरजौसि। चित्रा। वि। चरंति। तन्यवः। दिवः। सं। राजा। पयसा। नः। उक्षतं। वाचं।
सु। मित्रावरुणौ। इरांऽवतीं। पर्जन्यः। चित्रां। वदति। त्विषिऽमतीं। अभ्रा। वसत। मरुतः। सु। मा
यया। द्यां। वर्षतं। अरुणां। अरेपसं। धर्मणा। मित्रावरुणा। विपःऽचिता। व्रता। रक्षेथेइति।
असुरस्य। मायया। ऋतेन। विश्वं। भुवनं। वि। राजथः। सूर्यं। आ। धत्थः। दिवि। चित्र्यं। रथं।
॥३॥ वरुणं। वः। रिशादसं। ऋचा। मित्रं। हवामहे। परि। व्रजाऽइव। बाह्वोः। जगन्वांसा। स्वः
नरा। ता। बाहवा। सुऽचेतुना। प्र। यंत। अस्मै। अर्चते। शेवं। हि। जार्यं। वां। विश्वासु। क्षासु।
जोगुवे। यत्। नूनं। अश्यां। गतिं। मित्रस्य। यायां। पथा। अस्य। प्रियस्य। शर्मणि। अहिं

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ पं॰ सानस्य। सख्यिऽइव। सुवाभ्यां।। मित्रावरुणा। उप। मं। धेयां। ऋचा। यन्नू। हा। क्षये। मघोनां। स्तो
५१ तॄणां। च। स्पूर्धसे। आ। नः। मित्र। सुदीतिऽभिः। वरुणः। च। सधऽस्थे। आ। स्वे। क्षये। मघोनां।।
सखीनां। च। वृधसे। युवं। नः। येषु। वरुणा। क्षत्रं। बृहत्। च। बिभृथः। उरु। नः। वाजऽसातये।
51 कृतं। राये। स्वस्तये।। उछंत्यां। मे। यजता। देवऽक्षत्रे। रुशत्ऽगवि। सुते। सोमं। न। हस्तिऽभिः।
आ। पट्ऽभिः। धावतं। नरा। बिभ्रतो। अर्चनानसं।। रायः। चिकेत। सः। सुऽक्रतुः। देवऽत्रा। सः
ब्रवीतु। नः। वरुणः। यस्य। दर्शतः। मित्रः। वा। वनंते। गिरः।। ता। हि। श्रेष्ठऽवर्चसा। राजाना।
दीर्घश्रुत्ऽतमा।। ता। सत्पती इति सत्ऽपती। ऋतऽवृधा। ऋतऽवाना। जनेऽजने।। ता। वां। इया ५१

© Dharmartha Trust J&K. Digitized by eGangotri

नः।अवसे।पूर्वौ।उप।ब्रुवे।सचा।सुऽअश्वासः।सु।चेतुना।वाजान्।अभि।प्र।दावने।मित्रः।अं
होः।चित्।आत्।उरु।क्षयाय।गातुं।वनते।मित्रस्य।हि।प्रऽतूर्वतः।सुऽमतिः।अस्ति।विधतः।व
यं।मित्रस्य।अवसि।स्याम।सप्रथःऽतमे।अनेहसः।त्वाऽऊतयः।सत्रा।वरुणऽशेषसः।युवं।
मित्रा।इमं।जनं।यतथः।सं।च।नयथः।मा।मघोनः।परि।ख्यतं।मो इति।अस्माकं।ऋषीणां।
गोऽपीथे।नः।उरुष्यतं।६।आ।चिकितान।सुक्रतू इति सुऽक्रतू।देवौ।मर्त।रिशादसा।वरुणा
य।ऋतऽपेशसे।दधीत।प्रयसे।महे।ता।हि।क्षत्रं।अविऽह्रुतं।सम्यक्।असुर्यं।आशाते इति।
अध।व्रताऽइव।मानुषं।स्वः।न।धायि।दर्शतं।ता।वां।एषे।रथानां।उर्वीं।गव्यूतिं।एषां।रातऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ हव्यस्य। सुऽस्तुतिं। दधृक्। स्तोमैः। मनामहे। अध। हि। काव्या। युवं। दक्षस्य। पूःऽभिः। अद्भुता। नि। केतुना। ज
५२ नानां। चिकेथे इति। पूतऽदक्षसा। तत्। ऋतं। पृथिवि। बृहत्। श्रवःऽएषे। ऋषीणां। ज्रयसानौ। अरं। पृथु। अति।
क्षरंति। यामऽभिः। आ। यत्। वां। ईयऽचक्षसा। मित्रा। वयं। च। सूरयः। व्यचिष्ठे। बहुऽपाय्ये। यतेमहि। स्वःऽरा
ज्ये॥ ५१॥ बट्। इत्था। देवा। निःऽकृतं। आदित्या। यजतं। बृहत्। वरुण। मित्र। अर्यमन्। वर्षिष्ठं। क्षत्रं। आशाथे इ
ति। आ। यत्। योनिं। हिरण्ययं। वरुण। मित्र। सदथः। धर्तारा। चर्षणीनां। यंतं। सुम्नं। रिशादसा। विश्वे। हि। वि
श्वऽवेदसः। ०व्रना। व्रता। पदाऽइव। सश्चिरे। पांति। मर्त्यं। रिषः। ते। हि। सत्याः। ऋतऽस्पृशः। ऋतऽवानः। जनेऽजने।
सुऽनीथासः। सुऽदानवः। अंहोः। चित्। उरुऽचक्रयः। कः। नु। वां। मित्र। अस्तुतः। वरुणः। वा। तनूनां। तत्। सु। वां। ५२

52

© Dharmartha Trust J&K. Digitized by eGangotri

॥५॥

आ। ईषते। मतिः। अत्रिऽभ्यः। आ। ईषते। मुनिः। प्र। वः। मित्राय। गायत। वरुणाय। विपा। गिरा। महिऽक्षत्रौ।
ऋतं। बृहत्। संऽराजा। या। घृतयोनी इति घृतऽयोनी॥ मित्रः। च। उभा। वरुणः। च। देवा। देवेषु। प्रऽशस्ता।
ता। नः। शक्तं। पार्थिवस्य। महः। रायः। दिव्यस्य। महि। वां। क्षत्रं। देवेषु। ऋतं। ऋतेन। सपंता। इषिरं। दक्षं।
आशाते इति। अद्रुहा। देवौ। वर्धेते इति। वृष्टिऽद्यावा। रीतिऽआपा। इषः। पती इति। दानुऽमत्याः। बृहंतं।
गर्तं। आशाते इति॥ त्री। रोचना। वरुण। त्रीन्। उत। द्यून्। त्रीणि। मित्र। धारयथः। रजांसि। ववृधा
नौ। अमतिं। क्षत्रियस्य। अनु। व्रतं। रक्षमाणौ। असुर्यं। इराऽवतीः। वरुण। धेनवः। वां। मधुऽमत्। वां।
सिंधवः। मित्र। दुह्रे। त्रयः। तस्थुः। वृषभासः। तिसृणां। धिषणानां। रेतःऽधाः। वि। द्युऽमंतः। प्रातः। दे

© Dharmartha Trust J&K. Digitized by eGangotri

प.वे. वीं। अदितिं। जोहवीमि। मध्यंदिने। उतऽइता। सूर्यस्य। राये। मित्रावरुणा। सर्वऽताता। ईळे। तोकाय। तन
५२ याय। शं। योः। या। धर्तारा। रजसः। रोचनस्य। उत। आदित्या। दिव्या। पार्थिवस्य। न। वां। देवाः। अमृताः। आ
53 मिनंति। व्रतानि। मित्रावरुणा। ध्रुवाणि॥ ७॥ पुरुऽउरुणा। चित्। हि। अस्ति। अवः। नूनं। वां। वरुण। मित्र।
वंसि। वां। सुऽमतिं। ता। वां। सम्यक्। अद्रुह्वाणा। इषं। अश्याम। धायसे। वयं। ते। रुद्रा। स्याम। पातं। नः।
रुद्रा। पायुऽभिः। उत। त्रायेथां। सुऽत्रात्रा। तुर्याम। दस्यून्। तनूभिः। मा। कस्य। अद्भुतक्रतू इत्यद्भुतऽक्रतू। य
क्षं। भुजेम। तनूभिः। मा। शेषसा। मा। तनसा॥ ८॥ आ। नः। गंतं। रिशादसा। वरुण। मित्र। बर्हणा। उप। इ
मं। चारुं। अध्वरं। विश्वस्य। हि। प्रऽचेतसा। वरुण। मित्र। राजथः। ईशाना। पिप्यतं। धियः। उप। नः। सुतं। आ ५३

© Dharmartha Trust J&K. Digitized by eGangotri

गतं। वरुणा। मित्रा। दाभ्यथः॥ ०॥ १॥ आ। मित्रे। वरुणे। वयं। गीःऽभिः। जुहुमः। अत्रिऽवत्। नि। बर्हिषि। सदतं। सो

मऽपीतये। व्रतेन। स्थः। ध्रुवऽक्षेमा। धर्मणा। यातयत्ऽजना। ०। मित्रः। च। नः। वरुणः। च। जुषेतां। यज्ञं। इष्

ये। नि। बर्हिषि। सदतां। सोमऽपीतये॥ ॥१०॥ यत्। अद्य। स्थः। पराऽवति। यत्। अर्वाऽवति। अश्विना। यत्। वा।

पुरु। पुरुऽभुजा। यत्। अंतरिक्षे। आ। गतं। इह। स्या। पुरुऽभूतमा। पुरु। दंसांसि। बिभ्रता। वरस्या। यामि। अ

ध्रिगू इत्यध्रिऽगू। कुवे। नु। विऽनेमा। भुजे। ईमा। अन्यत्। वपुषि। वपुः। चक्रं। रथस्य। येमथुः। परि। अन्या।

नाहुषा। युगा। मह्ना। रजांसि। दीयथः। तत्। ऊं इति। सु। वां। एना। कृतं। विश्वा। यत्। वां। अनु। स्तवै। नाना।

जानौ। अरेपसा। सं। अस्मे इति। बंधुं। आ। ईयथुः। आ। यत्। वां। सूर्या। रथं। तिष्ठत्। रघुऽस्यदं। सदा। परि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चं॰ वां। अरुषाः। वयः। घृणा। वरंते। आऽतपः॥५॥ युवोः। अत्रिः। चिकेतति। नरा। सुम्नेन। चेतसा। घर्मं। यत्। वां।
५४ अरेपसं। नासत्या। आस्ना। भुरण्यति। उग्रः। वां। ककुहः। ययिः। शृण्वे। यामेषु। संऽतनिः। यत्। वां। दंसःऽ
भिः। अश्विना। अत्रिः। नरा। आऽववर्तति। मध्वः। ऊं इति। सु। मधुऽयुवा। रुद्रा। सिसक्ति। पिप्युषी। यत्। समुऽ
द्रा। अति। पर्षथः। पक्वाः। पृक्षः। भरंत। वां। सत्यं। इत्। वै। ऊं इति। अश्विना। युवां। आहुः। मयःऽभुवा। ता। या
मन्। यामऽहूतमा। यामन्। आ। मृळयत्ऽतमा। इमा। ब्रह्माणि। वर्धना। अश्विऽभ्यां। संतु। शंऽतमा। या।
तक्षाम। रथान्ऽइव। अवोचाम। बृहत्। नमः॥१०॥ कूऽस्थः। देवौ। अश्विना। अद्य। दिवः। मनावसू इति। त
त्। श्रवथः। वृषण्वसू इति वृषण्ऽवसू। अत्रिः। वां। आ। विवासति। कुह। त्या। कुह। नु। श्रुता। दिवि। देवा। नासऽ ५४

© Dharmartha Trust J&K. Digitized by eGangotri

सा। कस्मिन्। आ। यतथः। जने। कः। वां। नदीनां। सचा। कं। याथः। कं। ह। गच्छथः। कं। अच्छ। युंजाथे इति। र
थं। कस्य। ब्रह्माणि। रण्यथः। वयं। वां। उश्मसि। इष्टये। पौरं। चित्। हि। उदऽप्रुतं। पौर। पौराय। जिन्वथः। य
त्। ईं। गृभीतऽतातये। सिंहंऽइव। द्रुहः। पदे। आ। च्यवानात्। जुजुरुषः। वव्रिं। अत्कं। न। मुंचथः। युवा। यदि। कृ
थः। पुनः। आ। कामं। ऋण्वे। वध्वः। ॥५॥ अस्ति। हि। वां। इह। स्तोता। स्मसि। वां। संऽदृशि। श्रिये। नु। श्रुतं।
मे। आ। गतं। अवःऽभिः। वाजिनीवसू इति वाजिनीऽवसू। कः। वां। अद्य। पुरूणां। आ। वव्ने। मर्त्यानां। कः।
विप्रः। विप्रऽवाहसा। कः। यज्ञैः। वाजिनीवसू इति वाजिनीऽवसू। आ। वां। रथः। रथानां। येष्ठः। यातु। अश्वि
ना। पुरु। चित्। अस्मऽयुः। तिरः। आंगूषं। मर्त्येषु। आ। शं। ऊं इति। सु। वां। मधुऽयुवा। अस्माकं। अस्तु। चर्कृतिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. अर्वाचीना। विऽचेतसा। विऽभिः। श्येनाऽइव। दीयतं। अश्विना। यत्। हा। कर्हि। चित्। शुश्रुयातं। इ
५५ मं। हवं। वस्वीः। ऊं इति। सु। वां। भुजः। पृचंति। सु। वां। पृचः॥ ३२॥ प्रति। प्रियऽतमं। रथं। वृषणं। वसुऽवा
हनं। स्तोता। वां। अश्विनौ। ऋषिः। स्तोमेन। प्रति। भूषति। माध्वीइति। मम। श्रुतं। हवं। अति। आयातं। अ
श्विना। तिरः। विश्वाः। अहं। सना। दस्रा। हिरण्यवर्तनीइति हिरण्यऽवर्तनी। सुऽसुम्ना। सिंधुऽवाहसा।
०। आ। नः। रत्नानि। बिभ्रतौ। अश्विना। गच्छतं। युवं। रुद्रा। हिरण्यवर्तनीइति हिरण्यऽवर्तनी। जुषाणा। वा
जिनीवसूइति वाजिनीऽवसू। ०। सु। स्तुभः। वां। वृषण्वसूइति वृषणऽवसू। रथे। वाणीची। आऽहिता। उ
ता। वां। ककुहः। मृगः। पृक्षः। कृणोति। वापुषः। ० बोधिनऽमनसा। रथ्या। इषिरा। हवनऽश्रुता। विऽभिः। च्य ५५

© Dharmartha Trust J&K. Digitized by eGangotri

वां। अश्विना। नि। याथः। अद्वयाविनं। ०॥ १५॥ आ। वां। नरा। मनःऽयुजः। अश्वासः। प्रुषितऽप्सवः। वयः। व
हंतु। पीतये। सह। सुम्नेभिः। अश्विना। ०। अश्विनौ। आ। इह। गच्छतं। नासत्या। मा। वि। वेनतं। तिरः। चित्। अ
र्यःऽया। परि। वर्तिः। यातं। अदाभ्या। ०। अस्मिन्। यज्ञे। अदाभ्या। जरितारं। शुभः। पती इति। अवस्युं। अश्वि
ना। युवं। गृणंतं। उप। भूषथः। ०। अभूत्। उषाः। रुशत्ऽपशुः। आ। अग्निः। अधायि। ऋत्वियः। अयोजि। वां।
वृषण्वसू इति वृषणऽवसू। रथः। दस्रौ। अमर्त्यः। ०॥ १६॥ आ। भाति। अग्निः। उषसां। अनीकं। उत्। विप्रा
णां। देवऽयाः। वाचः। अस्थुः। अर्वांचा। नूनं। रथ्या। इह। यातं। पीपिऽवांसं। अश्विना। घर्मं। अछ। न। संस्कृ
तं। प्र। मिमीतः। गमिष्ठा। अंति। नूनं। अश्विना। उपऽस्तुता। इह। दिवा। अभिऽपित्वे। अवसा। आऽगमिष्ठा।

© Dharmartha Trust J&K. Digitized by eGangotri

प·च· प्रति। अवर्त्तिं। दाशुषे। शंऽभविष्ठा। उत। आ। यातं। संऽगवे। प्रातः। अह्नः। मध्यंदिने। उत्ऽइता। सूर्यस्य। आदि
५६ वा। नक्तं। अवसा। शंऽतमेन। न। इदानीं। पीतिः। अश्विना। आ। ततान। इदं। हि। वां। प्रऽदिवि। स्थानं। ओकः
58 इमे। गृहाः। अश्विना। इदं। दुरोणं। ०। अत्ऽभ्यः। यातं। इषं। ऊर्जं। वहन्ता। ०। ४॥ प्रातःऽयावाना। प्रथमा
यजध्वं। पुरा। गृध्रात्। अररुषः। पिबातः। प्रातः। हि। यज्ञं। अश्विना। दधाते इति। प्र। शंसंति। कवयः। पू
र्वऽभाजः। प्रातः। यजध्वं। अश्विना। हिनोत। न। सायं। अस्ति। देवऽयाः। अजुष्टं। उत। अन्यः। अस्मत्। यज
ते। वि। च। आवः। पूर्वःऽपूर्वः। यजमानः। वनीयान्। हिरण्यऽत्वक्। मधुऽवर्णः। घृतऽस्नुः। पृक्षः। वहन्। आ
रथः। वर्त्तते। वां। मनःऽजवाः। अश्विना। वातऽरंहाः। येन। अतिऽयाथः। दुःऽइतानि। विश्वा। यः। भूयि ५६

© Dharmartha Trust J&K. Digitized by eGangotri

षं।नासत्याभ्यां।वि।वेषा।च।निष्ठं।पित्वः।ररते।विऽभागे।सः।नोकं।अस्य।पीवरत्ना।शमीभिः।अनूर्ध्वऽभासः
।सदं।इत्।नु।तुर्यात्न।०॥९॥०।हंसौऽइव।पतन्तं।आ।सुताना।उप।अश्विना।हरिणौऽइव।गौरौऽइव।अनु।य
वसां।०।अश्विना।वाजिनीवसू इति वाजिनीऽवसू।जुषेथां।यज्ञं।इष्टये।०।अत्रिः।यत्।वां।अवऽरोहन्।ऋ
बीसं।अजोहवीत्।नाधमाना।ऽइव।योषा।श्येनस्य।चित्।जवसा।नूतनेन।आ।अगच्छतं।अश्विना।शंऽ
तमेन॥१०॥वि।जिहीष्व।वनस्पते।योनिः।सूष्यंत्याःऽइव।श्रुतं।मे।अश्विना।हवं।सप्तऽवध्रिं।च।मुंचतं।
भीताय।नाधमानाय।ऋषये।सप्तऽवध्रये।मायाभिः।अश्विना।युवं।वृक्षं।सं।च।वि।च।अचथः।यथा।वा
तः।पुष्करिणीं।संऽइङ्गयति।सर्वतः।एव।ते।गर्भः।एजतु।निःऽऐतु।दशऽमास्यः।यथा।वातः।यथा।वनं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰वं॰ यथा। समुद्रः। एजति। एव। त्वं। दशऽमास्य। सह। अव। इहि। जरायुणा। दश। मासान्। शशयानः। कुमारः। अ
५७ धि। मातरि। निःऽऐतु। जीवः। अक्षतः। जीवः। जीवन्त्याः। अधि। २०। मुहे। नः। अद्य। बोधय। उषः। राये। दिवि
57 त्मती। यथा। चित्। नः। अबोधयः। सत्यऽश्रवसि। वाय्ये। सुऽजाते। अश्वऽसूनृते। या। सुऽनीथा। शौचत्ऽर
थे। वि। औच्छः। दुहितः। दिवः। सा। वि। उच्छ। सहीयसि। ०। सा। नः। अद्य। आभरत्ऽवसुः। वि। उच्छ। दुहितः। दिवः।
यो इति। वि। औच्छः। ०। अभि। ये। त्वा। विभाऽवरि। स्तोमैः। गृणन्ति। वह्नयः। मघैः। मघोनि। सुऽश्रियः। दाम
न्ऽवंतः। सुऽरातयः। ०। गणाः। इमे। छदयन्ति। मघत्तये। परि। चित्। वष्टयः। दधुः। ददतः। राधः। अह्रयं। ०। २१।
आ। एषु। धाः। वीरऽवत्। यशः। उषः। मघोनि। सूरिषु। ये। नः। राधांसि। अह्रया। मघऽवानः। अरासत। ०। ते ५७

© Dharmartha Trust J&K. Digitized by eGangotri

भ्यः। द्युम्नं। बृहत्। यशः। उषः। मघोनि। आ। वह। ०। अश्व्या। गव्या। भजंत। सूरयः। ०। उत। नः। गोऽमतीः। इषः।
आ। वह। दुहितः। दिवः। साकं। सूर्यस्य। रश्मिऽभिः। शुक्रैः। शोचत्ऽभिः। अर्चिऽभिः। ०। वि। उच्छ। दुहितः। दिव
ः। मा। चिरं। तनुथाः। अपः। न। इत्। त्वा। स्तेनं। यथा। रिपुं। तपाति। सूरः। अर्चिषा। ०। एतावत्। वा। इत्। उषः।
त्वं। भूयः। वा। दातुं। अर्हसि। या। स्तोतृऽभ्यः। विभाऽवरि। उच्छंती। न। प्रऽमीयसे। ०। २२। द्युतत्ऽयामानं। बृ
हतीं। ऋतेन। ऋतऽवरीं। अरुणऽप्सुं। विऽभातीं। देवीं। उषसं। स्वः। आऽवहंतीं। प्रति। विप्रासः। मतिऽभिः।
जरंते। एषा। जनं। दर्शता। बोधयंती। सुऽगान्। पथः। कृण्वती। याति। अग्रे। बृहत्ऽरथा। बृहती। विश्वम्ऽइ
न्वा। उषाः। ज्योतिः। यच्छति। अग्रे। अह्नां। एषा। गोभिः। अरुणेभिः। युजाना। अस्रेधंती। रयिं। अप्रऽआयु।

© Dharmartha Trust J&K. Digitized by eGangotri

प.५. चक्रे।पथः।रदंती।सुविताय।देवी।पुरुऽस्तुता।विश्वऽवारा।वि।भाति।एषा।विऽएनी।भवति।द्विऽबर्हाः।आ
५८ विःऽकृण्वाना।तन्वं।पुरस्तात्।।एषा।शुभ्रा।न।तन्वः।विदाना।ऊर्ध्वाऽइव।स्नाती।दृशये।नः।अस्थात्
अप।द्वेषः।बाधमाना।तमांसि।उषाः।दिवः।दुहिता।ज्योतिषा।आ।अगात्।एषा।प्रतीची।दुहिता।दि
58 वः।नॄन्।योषाऽइव।भद्रा।नि।रिणीते।अप्सः।विऽऊर्ण्वती।दाशुषे।वार्याणि।पुनः।ज्योतिः।युवतिः।पूर्वऽ
था।अकरित्यकः।।२३।।युंजते।मनः।उत।युंजते।धियः।विप्राः।विप्रस्य।बृहतः।विपःऽचितः।वि।होत्राः।दधे।
वयुनऽवित्।एकः।इत्।मही।देवस्य।सवितुः।परिऽस्तुतिः।विश्वा।रूपाणि।प्रति।मुंचते।कविः।प्र।असावी
त्।भद्रं।द्विऽपदे।चतुःऽपदे।वि।नाकं।अख्यत्।सविता।वरेण्यः।अनु।प्रऽयानं।उषसः।वि।राजति।यस्य।प्र ५८

© Dharmartha Trust J&K. Digitized by eGangotri

याणं। अनु। अन्ये। इत्। ययुः। देवाः। देवस्य। महिमानं। ओजसा। यः। पार्थिवानि। विऽममे। सः। एतशः। रजां
सि। देवः। सविता। महिऽत्वना। उत। यासि। सवितरिति। त्रीणि। रोचना। उत। सूर्यस्य। रश्मिऽभिः। सं। उच्य
सि। उत। रात्रीं। उभयतः। परि। ईयसे। उत। मित्रः। भवसि। देव। धर्मऽभिः। उत। ईशिषे। प्रऽसवस्य। त्वं। एकः।
इत्। उत। पूषा। भवसि। देव। यामऽभिः। उत। इदं। विश्वं। भुवनं। वि। राजसि। श्यावऽअश्वः। ते। सवितरिति।
स्तोमं। आनशे॥५॥ तत्। सवितुः। वृणीमहे। वयं। देवस्य। भोजनं। श्रेष्ठं। सर्वऽधातमं। तुरं। भगस्य। धीम
हि। अस्य। हि। स्वयशःऽतरं। सवितुः। कत्। चन। प्रियं। न। मिनंति। स्वऽराज्यं। सः। हि। रत्नानि। दाशुषे। सुवा
ति। सविता। भगः। तं। भागं। चित्रं। ईमहे। अद्य। नः। देव। सवितरिति। प्रजाऽवत्। सावीः। सौभगं। परा। दुःस्व

© Dharmartha Trust J&K. Digitized by eGangotri

१५ ष्यं।सुव।विश्वानि।देव।सवितः।दुःऽइतानि।परा।सुव।यत्।भद्रं।तत्।नः।आ।सुव।२५।अनागसः।अदि
५८ तये।देवस्य।सवितुः।सवे।विश्वा।वामानि।धीमहि।आ।विश्वऽदेवं।सत्ऽपतिं।सुऽउक्तैः।अद्य।वृणीमहे।
सत्यऽसवं।सवितारं।यः।इमेइति।उभेइति।अहनीइति।पुरः।एति।अप्रऽयुच्छन्।सुऽआधीः।देवः।सविता।
59
यः।इमा।विश्वा।जातानि।आऽश्रवयति।श्लोकेन।प्र।च।सुवाति।सविता।२६।अच्छ।वद।तवसं।गीःऽभि
ः।आभिः।स्तुहि।पर्जन्यं।नमसा।आ।विवास।कनिक्रदत्।वृषभः।जीरऽदानुः।रेतः।दधाति।ओषधीषु।ग
र्भं।वि।वृक्षान्।हन्ति।उत।हन्ति।रक्षसः।विश्वं।बिभाय।भुवनं।महाऽवधात्।उत।अनागाः।ईषते।वृष्ण्यऽव
तः।यत्।पर्जन्यः।स्तनयन्।हन्ति।दुःऽकृतः।रथीऽइव।कशया।अश्वान्।अभिऽक्षिपन्।आविः।दूतान्।कृ ५९

© Dharmartha Trust J&K. Digitized by eGangotri

गुते।वृष्ण्यानि।आरात्।दूरात्।सिंहस्य।स्तनथाः।उत्।ईरते।यत्।पर्जन्यः।कृणुते।वर्ष्यं।नभः।प्र।वाताः।वांति।
पतयंति।विऽद्युतः।उत्।ओषधीः।जिहते।पिन्वते।स्वः।इरा।विश्वस्मै।भुवनाय।जायते।यत्।पर्जन्य
ःपृथिवीं।रेतसा।अवति।यस्य।व्रते।पृथिवी।नन्नमीति।यस्य।व्रते।शफऽवत्।जर्भुरीति।यस्य।व्रते।ओष
धीः।विश्वऽरूपाः।सः।नः।पर्जन्य।महि।शर्म।यच्छ।रग्।दिवः।नः।वृष्टिं।मरुतः।ररीध्वं।प्र।पिन्वत।वृष्णः।अ
श्वस्य।धाराः।अर्वाङ्।एतेन।स्तनयित्नुना।आ।इहि।अपः।निऽसिंचन्।असुरः।पिता।नः।अभि।क्रंद।स्त
नय।गर्भं।आ।धाः।उदन्ऽवता।परि।दीय।रथेन।दृतिं।सु।आकर्ष।विऽसितं।न्यंचं।समाः।भवंतु।उत्ऽवतः
।निऽपादाः।महांतं।कोशं।उत्।अच।नि।सिंच।स्यंदंतां।कुल्याः।विऽसिताः।पुरस्तात्।घृतेन।द्यावापृथि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ब॰ वी इति। वि। उन्धि। सुऽप्रपानं। भवतु। अघ्न्याभ्यः। यत्। पर्जन्य। कनिक्रदत्। स्तनयन्। हंसि। दुःऽकृतः। प्र

७० ति। इदं। विश्वं। मोदते। यत्। किं। च। पृथिव्यां। अधि। अवर्षीः। वर्षं। उत्। ऊं इति। सु। गृभाय। अकः। धन्वा

60 नि। अतिऽएतवै। ऊं इति। अजीजनः। ओषधीः। भोजनाय। कं। उत। प्रऽजाभ्यः। अविदः। मनीषां॥ २० ॥ बट्

इत्था। पर्वतानां। खिद्रं। बिभर्षि। पृथिवि। प्र। या। भूमिं। प्रवत्वति। मह्ना। जिनोषि। महिनि। स्तोमासः।

त्वा। विऽचारिणि। प्रति। स्तोभन्ति। अक्तुऽभिः। प्र। या। वाजं। न। हेषन्तं। पेरुं। अस्यसि। अर्जुनि। दृळ्हा। चि

त्। या। वनस्पतीन्। क्ष्मया। दर्धर्षि। ओजसा। यत्। ते। अभ्रस्य। विऽद्युतः। दिवः। वर्षन्ति। वृष्टयः॥ २१ ॥ प्र

सम्ऽराजे। बृहत्। अर्च। गभीरं। ब्रह्म। प्रियं। वरुणाय। श्रुताय। वि। यः। जघान। शमिताऽइव। चर्म। उपऽस्ति ७०

© Dharmartha Trust J&K. Digitized by eGangotri

रो । पृथिवीं । सूर्याय । वनेषु । वि । अंतरिक्षं । ततान । वाजं । अर्वत्ऽसु । पयः । उस्रियासु । हृत्ऽसु । क्रतुं । वरुण
ः । अप्ऽसु । अग्निं । दिवि । सूर्यं । अदधात् । सोमं । अद्रौ । नीचीनऽबारं । वरुणः । कबंधं । प्र । ससर्ज । रोदसी
इति । अंतरिक्षं । तेन । विश्वस्य । भुवनस्य । राजा । यवं । न । वृष्टिः । वि । उनत्ति । भूम । उनत्ति । भूमिं । पृथिवीं ।
उत । द्यां । यदा । दुग्धं । वरुणः । वष्टि । आत् । इत् । तं । अभ्रेण । वसत । पर्वतासः । तविषीऽयंतः । श्रथयंत । वी
राः । इमां । ऊं इति । सु । आसुरस्य । श्रुतस्य । महीं । मायां । वरुणस्य । प्र । वोचं । मानेनऽइव । तस्थिऽवान् । अं
तरिक्षे । वि । यः । ममे । पृथिवीं । सूर्येण ॥ ५ ॥ इमां । ऊं इति । नु । कविऽतमस्य । मायां । महीं । देवस्य । नकिः ।
आ । दधर्ष । एकं । यत् । उद्ना । न । पृणंति । एनीः । आऽसिंचंतीः । अवनयः । समुद्रं । अर्यम्यं । वरुण । मित्र्यं । वा ।

© Dharmartha Trust J&K. Digitized by eGangotri

१.४. सख्यायं। वां। सदः। इत्। मा। अध्वरं। वा। वृशं। वा। नियं। वरुणा। अरणं। वा। यत्। आसीं। आगः। प्रुष्मा। शिश्रथः। नन्। कि
६३ तवासः। यत्। रिरिषुः। नाहि। वियत्। वा। घा। सखा। उत। यत्। नाविन। सचौ। ना। वि। स्या। शिथिरा ऽइव। देवा। अध
५१ तोस्याम। वरुणा। प्रियासः॥ इंद्राग्नीइति। यं। अवथः। उभा। वाजेषु। मर्त्यं। दृढा। चित्। सः। प्र। भेदति। द्यु
म्ना। वाणीः ऽइव। त्रितः। या। पृतनासु। दुस्तरा। या। वाजेषु। श्रवाय्या। या। पंच। चर्षणीः। अभि। इंद्राग्नीइति।
ता। हुवामहे। तयोः। इत्। अमऽवत्। शवः। तिग्मा। दिद्युत्। मघोनोः। प्रति। द्रुणा। गभस्त्योः। गवां। वृत्रऽघ्ने।
आ। ईषते। इंद्राग्नीइति। हुवामहे। पतीइति। तुरस्य। राधसः। विद्वांसा। गिर्वणःऽतमा। ता। हु। धंतौ। अनु।
द्यून्। मर्ताय। देवौ। अदभा। अर्हंता। चित्। पुरः। दधे। अंशाऽइव। देवौ। अर्वते। एव। इंद्राग्निऽभ्यां। अहावि। ६३

© Dharmartha Trust J&K. Digitized by eGangotri

हव्यं । शूष्यं । घृतं । न । पूतं । अद्रिभिः । ता । सूरिषु । श्रवः । बृहत् । रयिं । गृणत्ऽसु । दिधृतं । इषं । गृण
त्ऽसु । दिधृतं ॥ ६ ॥ प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिऽजाः । एवयामरुत् । प्र । शर्धा
य । प्रऽयज्यवे । सुऽखादये । तवसे । भन्दत्ऽइष्टये । धुनिऽव्रताय । शवसे । प्र । ये । जाताः । महिना । ये । च ।
नु । स्वयं । प्र । विद्मना । ब्रुवते । एवयामरुत् । क्रत्वा । तत् । वः । मरुतः । न । आऽधृषे । शवः । दाना । मह्ना । तत् ।
एषां । अधृष्टासः । न । अद्रयः । प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सुऽशुक्वानः । सुऽभ्वः । एवयामरुत् ।
न । येषां । इरी । सधऽस्थे । ईष्टे । आ । अग्नयः । न । स्वऽविद्युतः । प्र । स्यन्द्रासः । धुनीनां । सः । चक्रमे । महतः ।
निः । उरुऽक्रमः । समानस्मात् । सदसः । एवयामरुत् । यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुऽभिः । वि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ क॰ स्पर्धसः। विऽमहसः। जिगाति। शेऽवृधः। नृऽभिः। स्वनः। ना। वः। अमऽवान्। रेजयत्। वृषा। त्वेषः। ययिः। तवि
६२ षः। एवयामरुत्। येन। सहन्तः। ऋंजत। स्वऽरोचिषः। स्थाःऽरश्मानः। हिरण्ययाः। सुऽआयुधासः। इष्मिण
62 ः॥३३॥ अपारः। वः। महिमा। वृद्धऽशवसः। त्वेषं। शवः। अवतु। एवयामरुत्। स्थातारः। हि। प्रऽसितौ। संऽदृ
शि। स्थन। ते। नः। उरुष्यत। निदः। शुशुक्वांसः। न। अग्नयः। ते। रुद्रासः। सुऽमखाः। अग्नयः। यथा। तुविऽद्यु
म्नाः। अवंतु। एवयामरुत्। दीर्घं। पृथु। पप्रथे। सद्म। पार्थिवं। येषां। अज्मेषु। आ। महः। शर्धांसि। अद्भुतऽ
एनसां। अद्वेषः। नः। मरुतः। गातुं। आ। इतन। श्रोत। हवं। जरितुः। एवयामरुत्। विष्णोः। महः। सऽमन्यवः।
युयोतन। स्मत्। रथ्यः। न। दंसना। अप। द्वेषांसि। सनुतरिति। गंत। नः। यज्ञं। यज्ञियाः। सुऽशमि। श्रोत। ६२

© Dharmartha Trust J&K. Digitized by eGangotri

हवं। अरक्षः। अेवयाऽमरुत्। ज्येष्ठासः। न। पर्वतासः। विऽओमनि। यूयं। तस्य। प्रऽचेतसः। स्यात। दुःऽधर्त
वः। निदः॥ ३५॥ इति पंचमं मंडलं॥ अनुवाकः॥ त्वं। हि। अग्ने। प्रथमः। मनोता। अस्याः। धियः। अभवः।
दस्म। होता। त्वं। सीं। वृषन्। अकृणोः। दुस्तरीतु। सहः। विश्वस्मै। सहसे। सहध्यै। अध। होता। नि। असी ह
दः। यजीयान्। इळः। पदे। इषयन्। ईड्यः। सन्। तं। त्वा। नरः। प्रथमं। देवऽयंतः। महः। राये। चितयंतः। अनु।
ग्मन्। वृताऽइव। यंतं। बहुऽभिः। वसव्यैः। त्वेइति। रयिं। जागृऽवांसः। अनु। ग्मन्। रुशंतं। अग्निं। दर्शतं।
बृहंतं। वपाऽवंतं। विश्वहा। दीदिऽवांसं। पदं। देवस्य। नमसा। व्यंतः। श्रवस्यवः। श्रवः। आपन्। अमृक्तं। व
ग। भद्रायां। ते। रणयंत। संऽदृष्टौ। त्वां। वर्धंति। क्षितयः। पृथिव्यां। त्वां। रायः। उभयासः। जनानां। त्वं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. त्राता।तरणा।चेत्यः।भूः।पिता।माता।सदा।इत्।मानुषाणां॥२५॥सपर्येण्यः।सः।प्रियः।विक्षु।अ
६२ ग्निः।होता।मंद्रः।नि।ससाद।यजीयान्।तं।त्वा।वयं।दमे।आ।दीदिऽवांसं।उप।ज्ञुऽबाधः।नमसा।
63 सदेम।०।सुऽध्यः।नव्यं।अग्ने।सुम्नऽयवः।ईमहे।देवऽयंतः।त्वं।विशः।अनयः।दीद्यानः।दिवः।अग्ने।
बृहता।रोचनेन।०।शश्वतीनां।नितोशनं।वृषभं।चर्षणीनां।प्रेतिऽइषणिं।इषयंतं।पावकं।राजंतं।
अग्निं।यजतं।रयीणां।सः।अग्ने।ईजे।शशमे।च।मर्तः।यः।ते।आनट्।संऽइधा।हव्यऽदातिं।०।नमःऽ
भिः।विश्वा।इत्।सः।धामा।दधते।त्वाऽऊतः।अस्मै।ऊं इति।ते।महि।महे।विधेम।नमःऽभिः।अग्ने।संऽ
इधा।उत।हव्यैः।वेदी।सूनो।इति।सहसः।गीःऽभिः।उक्थैः।आ।ते।भद्रायां।सुऽमतौ।यतेम।आ।यः।त ६२

© Dharmartha Trust J&K. Digitized by eGangotri

तंथ।रोदसीइति।वि।भासा।श्रवःऽभिः।च।श्रवस्यः।तरुत्रः।बृहत्ऽभिः।वाजैः।स्थविरऽभिः।अस्मेइति।रेव
त्ऽभिः।अग्ने।वितरं।विभाहि।ऋत्ऽवत्।वसोइति।सदं।इत।धेहि।अस्मेइति।भूरि।तोकाय।तनयाय।प
श्वः।पूर्वीः।इषः।बृहतीः।आरेऽअघाः।अस्मेइति।भद्रा।सौश्रवसानि।संतु।पुरूणि।अग्ने।पुरुधा।त्वाऽ
या।वसूनि।राजन्।वसुता।ते।अश्यां।पुरूणि।हि।त्वेइति।पुरुऽवार।संति।अग्ने।वसु।विधते।राजनि।
त्वेइति॥३६॥ ॥इति चतुर्थाष्टके चतुर्थोध्यायः॥ ॐ नमः॥ त्वंह्येकादशानुष्टुभंशाक्त्यंतंनमग्नेष्टौयथाहोत
र्द्धेवेसमेव्रनव्यसामूर्धानंपेश्वानरीयंहिद्धिजगत्संतंप्रदाख्यांस्यात्रिष्टुब्बृहत्यश्वपरोवोह्निपदांतंयजस्व
पणमध्येत्वद्धिश्वाग्नायआनुष्टुभंशाक्त्यंतंमिमम्रूषेकोनावीनहव्यऋषिर्वाजागतंप्रागदशम्यास्तत्री

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ यापंचदश्योराक्कयौषस्यातिशाक्कर्यनुष्टुप्बृहत्साद्यपांसे॰त्वमग्नेष्टाचत्वारिंशग्दायत्रंवर्धमानाद्यापङ्क्तीर्वस
६४ प्तविंश्यनुष्टुप्त्रिष्टुप्पूर्वेचांत्ये॥ॐ त्वं। हि। क्षैतऽवत्। यशः। अग्ने। मित्रः। न। पत्यसे। त्वं। विऽचर्षणे। श्रवः।
वसो इति। पुष्टिं। न। पुष्यसि। त्वं। हि। स्म। चर्षणयः। यज्ञेभिः। गीःऽभिः। ईळते। त्वां। वाजी। याति। अवृकः।
रजःऽतूः। विश्वऽचर्षणिः। सऽजोषः। त्वा। दिवः। नरः। यज्ञस्य। केतुं। इंधते। यत्। ह। स्यः। मानुषः। जनः। सुम्नऽ
युः। जुह्वे। अध्वरे। ऋधत्। यः। ते। सुऽदानवे। धिया। मर्तः। शशमते। ऊती। सः। बृहतः। दिवः। द्विषः। अंहः। न।
तरति। सं। इध्या। यः। ते। आऽहुतिं। निऽशितिं। मर्त्यः। नशत्। वयाऽवंतं। सः। पुष्यति। क्षयं। अग्ने। शतऽआयु
षं॥ १॥ त्वेषः। ते। धूमः। ऋण्वति। दिवि। सन्। शुक्रः। आऽततः। सूरः। न। हि। द्युता। त्वं। कृपा। पावक। रोचसे। ६४

© Dharmartha Trust J&K. Digitized by eGangotri

अध। हि। विक्षु। ईड्यः। असि। प्रियः। नः। अतिथिः। रण्वः। पुरिऽइव। जूर्यः। सूनुः। न। त्रययाय्यः। क्रत्वा। हि। द्रो
णे। अज्यसे। अग्ने। वाजी। न। कृत्व्यः। परिज्माऽइव। स्वधा। गयः। अत्यः। न। ह्वार्यः। शिशुः। त्वं। त्या। चित्। अ
च्युता। अग्ने। पशुः। न। यवसे। धाम। ह। यत्। ते। अजर। वना। वृश्चन्ति। शिक्वसः। ८ अग्ने। होता। दमे। वि
शां। संऽऋधः। विश्पते। कृणु। जुषस्व। हव्यं। अंगिरः। अछ। नः। मित्रऽमहः। देव। देवान्। अग्ने। वोचः। सुऽम
तिं। रोदस्योः। वीहि। स्वस्तिं। सुऽक्षितिं। दिवः। नॄन्। द्विषः। अंहांसि। दुःऽइता। तरेम। ता। तरेम। तव। अवसा
। तरेम। ११। अग्ने। सः। क्षेषत्। ऋतऽपाः। ऋतेऽजाः। उरु। ज्योतिः। नशते। देवऽयुः। ते। यं। त्वं। मित्रेण। वरुणः।
सऽजोषाः। देव। पासि। त्यजसा। मर्तं। अंहः। ईजे। यज्ञेभिः। शशमे। शमीभिः। ऋधत्ऽवारा य। अग्नये। ददा

© Dharmartha Trust J&K. Digitized by eGangotri

प.वं. शा। एवा। चना। ले। यशसां। अजुष्टिः। ना। अंहः। मर्त्तों। नशनै। ना। त्रः। दमितः। सूरः। ना। यस्य। दशा। तिः। अरेपा। भी

६५ मा। यत्। एतिः। भुचनः। ने। आधीः। हेषस्वनः। श्रुरुधः। ना। अपां। अक्तोः। कुत्रा। चिल्। रण्वः। वसतिः। वनेः

जाः। तिग्मं। चित्। एमा। महि। वर्पः। अस्य। भसत्। अश्वः। ना। यमसानः। आसा। विजेहमानः। परशुः। ना।

जिह्वां। द्रविः। ना। द्रवयति। दारु। धक्षत्। सः। इत्। अस्तो। ऽइव। धाम। इति। धात्। असितस्य। नः। शिशीता। तेजः। अय

सः। ना। धारां। चित्रः। ऽध्रजतिः। अरतिः। यः। अक्तोः। वेः। ना। द्रुऽसद्वा। रघुपत्मऽजंहाः। आ। सः। ईरेभः। प्र ना।

तिः। वस्ने। उस्त्राः। शोचिषा। ररपीति। मित्रः। महाः। नक्षे। यः। ई। अहृपः। यः। दिवा। नृन्। अमर्त्यः। अहृपः।

यः। दिवा। नृन्। दिवः। ना। यस्य। विधतः। नवीनोत्। वृषा। रुक्षः। ओषधीषु। नूनोत्। घृणा। ना। यः। ध्र ६५

© Dharmartha Trust J&K. Digitized by eGangotri

त्ने।सा।पत्मना।स्यन्द्रा।आ।रोदसीइति।वसुना।दं।सुपत्नीइति सुऽपत्नी।धायसे।अभि।वा।यः।शुभ्रेभिः।अर्कैः।वि
ऽद्युता।ना।दविद्योत्।स्वेभिः।शुष्मैः।शर्धः।वा।अयः।मरुताम्।न।नक्ष।ऋभुः।ना।वेषः।रभसा।नः।अद्यौत्॥धा।य
था।होतारः।मनुषः।देवऽताता।यज्ञेभिः।सूनोइति।सहसः।यजासि।एवा।नः।अद्य।समना।समाना।उशन्
अग्ने।उशतः।यक्षि।देवान्।सः।नः।विभाऽवा।चक्षणिः।न।वस्तोः।अग्निः।वन्दारु।वेद्यः।चनः।धात्॥वि
श्वऽआयुः।यः।अमृतः।मर्त्येषु।उषःऽभुत्।भूत्।अतिथिः।जातऽवेदाः॥द्यावः।न।यस्य।पनयन्ति।अभ्वं।भा
सांसि।वस्ते।सूर्यः।न।शुक्रः।वि।यः।इनोति।अजरः।पावकः।अश्नस्य।चित्।शिश्नथत्।पूर्व्याणि॥वस्ता
हिः।सूनोइति।असि।अ ह्मऽसद्वा।चक्रे।अग्निः।जनुषा।अज्म।अन्नं।सः।त्वं।नः।ऊर्जऽसने।ऊर्जं।धाः।

© Dharmartha Trust J&K. Digitized by eGangotri

तं

प.व. राजऽइव। जेः। अवृके। क्षिषि। अंतरिति। निऽतिक्ति। यः। वारणं। अन्नं। अत्ति। वायुः। न। राष्ट्री। अति। एति। अ-
६६ क्तून्। तुर्याम। यः। ते। आऽदिशां। अरातीः। अत्यः। न। ह्रुतः। पततः। परिऽह्रुत्॥५॥ आ। सूर्यः। न। भानुमत्ऽभिः।
अर्कैः। अग्ने। ततंथ। रोदसी इति। वि। भासा। चित्रः। नयत्। परि। तमांसि। अक्तः। शोचिषा। पत्मन्। औशि-
जः। न। दीयन्॥६॥ त्वां। हि। मंद्रऽतमं। अर्कऽशोकैः। ववृमहे। महि। नः। श्रोषि। अग्ने। इंद्रं। न। त्वा। शवसा। देवता।
वायुं। पृणंति। राधसा। नृऽतमाः॥७॥ नु। नः। अग्ने। अवृकेभिः। स्वस्ति। वेषि। रायः। पथिऽभिः। पर्षि। अंहः। ता।
सूरिऽभ्यः। गृणते। रासि। सुम्नं। मदेम। शतऽहिमाः। सुऽवीराः॥८॥ हुवे। वः। सूनुं। सहसः। युवानं। अद्रोघ-
ऽवाचं। मतिऽभिः। यविष्ठं। यः। इन्वति। द्रविणानि। प्रऽचेताः। विश्वऽवाराणि। पुरुऽवारः। अध्रुक्। त्वे इति। व ६६

© Dharmartha Trust J&K. Digitized by eGangotri

सूनि। पुरु। अनीक। होतः। दोषा। वस्तोः। आ। ईरिरे। यज्ञियासः। क्षामऽइव। विश्वा। भुवनानि। यस्मिन्।
सं। सौभगानि। दधिरे। पावके। त्वं। विक्षु। प्रऽदिवः। सीदः। आसु। क्रत्वा। रथीः। अभवः। वार्याणां। अग्नेः।
इनोषि। विधते। चिकित्वः। वि। आनुषक्। जातऽवेदः। वसूनि। यः। नः। सनुत्यः। अभिऽदासत्। अग्ने। यः।
अंतरः। मित्रऽमहः। वनुष्यात्। तं। अजरेभिः। वृषऽभिः। तव। स्वैः। तप। तपिष्ठ। तपसा। तपस्वान्। यः। ते। य
ज्ञेन। सं। इधा। यः। उक्थैः। अर्केभिः। सूनो इति। सहसः। ददाशत्। सः। मर्त्येषु। अमृत। प्रऽचेताः। राया। द्युम्ने
न। श्रवसा। वि। भाति। सः। तत्। कृधि। इषितः। तूयं। अग्ने। स्पृधः। बाधस्व। सहसा। सहस्वान्। यत्। श
स्यसे। द्युऽभिः। अक्तः। वचःऽभिः। तत्। जुषस्व। जरितुः। घोषि। मन्म। अश्याम। तं। कामं। अग्ने। तव। ऊ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ध॰ ती। अश्याम। रयिं। रयिऽवः। सुऽवीरं। अश्याम। वाजं। अभि। वाजयंतः। अश्याम। द्युम्नं। अजर। अजरं। ते।
६७ ॥ ७॥ प्र। नव्यसा। सहसः। सूनुं। अच्छ। यज्ञेन। गातुं। अवः। इच्छमानः। वृश्चत्ऽवनं। कृष्णऽयामं। रुशंतं।
67 वीती। होतारं। दिव्यं। जिगाति॥ सः। श्वितानः। तन्यतुः। रोचनऽस्थाः। अजरेभिः। नानदत्ऽभिः। यविष्ठः। य
ः। पावकः। पुरुऽतमः। पुरूणि। पृथूनि। अग्निः। अनुऽयाति। भर्वन्॥ वि। ते। विष्वक्। वातऽजूतासः। अग्ने।
भामासः। शुचे। शुचयः। चरंति। तुविऽम्रक्षासः। दिव्याः। नवऽग्वाः। वना। वनंति। धृषता। रुजंतः॥ ये। ते।
शुक्रासः। शुचयः। शुचिष्मः। क्षां। वपंति। विऽसितासः। अश्वाः। अध। भ्रमः। ते। उर्विया। वि। भाति। या
तयमानः। अधि। सानु। पृश्नेः॥ अध। जिह्वा। पापतीति। प्र। वृष्णः। गोऽसुऽयुधः। न। अशनिः। सृजाना। ६७

© Dharmartha Trust J&K. Digitized by eGangotri

शूरस्यऽइव। प्रऽसितिः। क्षातिः। अग्नेः। दुःऽवर्तुः। भीमः। दयते। वनानि। आ। भानुना। पार्थिवानि। ज्रयांसि।
महः। तोदस्य। धृषता। ततंथ। सः। बाधस्व। अप। भया। सहःऽभिः। स्पृधः। वनुष्यन्। वनुषः। नि। जूर्व। सः।
चित्र। चित्रं। चितयंतं। अस्मे इति। चित्रऽक्षत्र। चित्रऽतमं। वयःऽधां। चंद्रं। रयिं। पुरुऽवीरं। बृहंतं। चंद्र। चंद्र
भिः। गृणते। युवस्व॥ ७॥ मूर्धानं। दिवः। अरतिं। पृथिव्याः। वैश्वानरं। ऋते। आ। जातं। अग्निं। कविं। संऽराजं
। अतिथिं। जनानां। आसन्। आ। पात्रं। जनयंत। देवाः। नाभिं। यज्ञानां। सदनं। रयीणां। महां। आऽहावं। अ
भि। सं। नवंत। वैश्वानरं। रथ्यं। अध्वराणां। यज्ञस्य। केतुं। जनयंत। देवाः। त्वत्। विप्रः। जायते। वाजी। अग्ने।
त्वत्। वीरासः। अभिमातिऽसहः। वैश्वानर। त्वं। अस्मासु। धेहि। वसूनि। राजन्। स्पृहयाय्याणि। त्वां। विश्वे।

© Dharmartha Trust J&K. Digitized by eGangotri

प.चं. अमृत।जायमानं।शिशुं।न।देवाः।अभि।सं।नवंते।तव।क्रतुऽभिः।अमृतऽत्वं।आयन्।वैश्वानर।यत्।
६८ पित्रोः।अदीदेः।वैश्वानर।तव।तानि।व्रतानि।महानि।अग्ने।नकिः।आ।दधर्ष।यत्।जायमानः।पित्रोः।
उपऽस्थे।अविंदः।केतुं।वयुनेषु।अह्नां।वैश्वानरस्य।विऽमितानि।चक्षसा।सानूनि।दिवः।अमृतस्य।
केतुना।तस्य।इत्।ऊं इति।विश्वा।भुवना।अधि।मूर्धनि।वयाःऽइव।रुरुहुः।सप्त।विऽस्रुहः।वियः।राजो
सि।अमीमित।सुऽक्रतुः।वैश्वानरः।वि।दिवः।रोचना।कविः।परि।यः।विश्वा।भुवनानि।पप्रथे।अदब्धः
।गोपाः।अमृतस्य।रक्षिता॥ १॥ पृक्षस्य।वृष्णः।अरुषस्य।नु।सहः।प्र।नु।वोचं।विदथा।जातऽवेदसः।
वैश्वानराय।मतिः।नव्यसी।शुचिः।सोमःऽइव।पवते।चारुः।अग्नये।व्रतानि।अग्निः।व्रतऽपाः।अर ६८

© Dharmartha Trust J&K. Digitized by eGangotri

सता । वि । अंतरिक्षं । अमिमीत । सुऽक्रतुः । वैश्वानरः । महिना । नाकं । अस्पृशत् । वि । अस्तभ्नात् । रोदसी
इति । मित्रः । अद्भुतः । अंतः । वा । वत् । अकृणोत् । ज्योतिषा । तमः । वि । चर्मणीइवेति चर्मणीऽइव । धिषणे इति
। अवर्त्तयत् । वैश्वानरः । विश्वं । अधत्त । वृष्ण्यं । अपां । उपऽस्थे । महिषाः । अगृभ्णत् । विशः । राजानं । उप ।
तस्थुः । ऋग्मियं । आ । दूतः । अग्निं । अभरत् । विवस्वतः । वैश्वानरं । मातरिश्वा । पराऽवतः । युगेऽयुगे । वि
दथ्यं । गृणत्ऽभ्यः । अग्ने । रयिं । यशसं । धेहि । नव्यसीं । पव्याऽइव । राजन् । अघऽशंसं । अजर । नीचा । नि
। वृश्च । वनिनं । न । तेजसा । ० । धारय । अनामि । क्षत्रं । अजरं । सुऽवीर्यं । वयं । जयेम । शतिनं । सहस्रिणं ।
। वैश्वानर । वाजं । अग्ने । तव । ऊतिऽभिः । अदब्धेभिः । तव । गोपाभिः । इषे । अस्माकं । पाहि । त्रिऽसधस्थ ।

© Dharmartha Trust J&K. Digitized by eGangotri

प·प·

६९

59

सूरीन्।रक्ष।च।नः।ददुषां।शर्धः।अग्ने।वैश्वानर।प्र।च।ना।रीः।स्तवानः॥१०॥अहः।च।कृष्णं।अ
हः।अर्जुनं।च।वि।वर्तेते इति।रजसी इति।वेद्याभिः।वैश्वानरः।जायमानः।न।राजा।अव।अतिरत्।
ज्योतिषा।अग्निः।तमांसि।न।अहं।तंतुं।न।वि।जानामि।ओतुं।न।यं।वयंति।संऽअरे।अतमानाः।क
स्य।स्वित्।पुत्रः।इह।वक्त्वानि।परः।वदाति।अवरेण।पित्रा।सः।इत्।तंतुं।सः।वि।जानाति।ओतुं।सः।
वक्त्वानि।ऋतुऽथा।वदाति।यः।ईं।चिकेतत्।अमृतस्य।गोपाः।अवः।चरन्।परः।अन्येन।पश्यन्।अ
यं।होता।प्रथमः।पश्यत।इमं।इदं।ज्योतिः।अमृतं।मर्त्येषु।अयं।सः।जज्ञे।ध्रुवः।आ।निऽसत्तः।अम
र्त्यः।तन्वा।वर्धमानः॥ध्रुवं।ज्योतिः।निऽहितं।दृशये।कं।मनः।जविष्ठं।पतयत्ऽसु।अंतरिति।विश्वे।दे ६९

© Dharmartha Trust J&K. Digitized by eGangotri

वाः।सऽमनसः।सऽकेताः।एकं।क्रतुं।अभि।वि।यंति।साधु।वि।मे।कर्णा।पतयतः।वि।चक्षुः।वि।इदं।ज्यो
तिः।हृदये।आऽहितं।यत्।वि।मे।मनः।चरति।दूरेऽआधीः।किं।स्वित्।वक्ष्यामि।किं।ऊं इति।नु।मनिष्ये
।विश्वे।देवाः।अनमस्यन्।भियानाः।त्वां।अग्ने।तमसि।तस्थिवांसं।वैश्वानरः।अवतु।ऊतये।नः।अ
मर्त्यः।अवतु।ऊतये।नः॥१॥पुरः।वः।मंद्रं।दिव्यं।सुऽवृक्तिं।प्रऽयति।यज्ञे।अग्निं।अध्वरे।दधिध्वं।पु
रः।उक्थेभिः।सः।हि।नः।विभाऽवा।सुऽअध्वरा।करति।जातऽवेदाः।तं।ऊं इति।द्युऽमः।पुरुऽअनीक।होतः
।अग्ने।अग्निऽभिः।मनुषः।इधानः।स्तोमं।यं।अस्मै।ममताऽइव।शूषं।घृतं।न।शुचि।मतयः।पवंते।पी
पाय।सः।श्रवसा।मर्त्येषु।यः।अग्नये।ददाश।विप्रः।उक्थैः।चित्राभिः।तं।ऊतिऽभिः।चित्रऽशोचिः।व्रजस्य

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ ७० सः।अस्ता।गोः।मनः।दधाति।आ।वः।पश्रो।आयमानः।ऊर्वी इति।दूरेऽदृशा।भासा।कृष्णऽअध्वा।अध।बृहु

चित्।नमः।ऊर्म्यायाः।तिरः।शोचिषा।ददृशे।पावकः।नु।नः।चित्रं।पुरुऽवाजाभिः।ऊती।अग्ने।रयिं।मघव जा

70 त्ऽभ्यः।च।धेहि।ये।राधसा।श्रवसा।च।अति।अन्यान्।सुऽवीर्येभिः।च।अभि।संति।जनान्।इमं।यज्ञं

चनः।धाः।अग्ने।उशन्।यं।ते।आसानः।जुहुते।हविष्मान्।भरतऽवाजेषु।दधिषे।सुऽवृक्तिं।अवीः।वा

जस्य।गध्यस्य।सातौ।वि।द्वेषांसि।इनुहि।वर्धय।इळां।ग।२३।यजस्व।होतः।इषितः।यजीयान्।अ

ग्ने।बाधः।मरुतां।न।प्रऽयुक्ति।आ।नः।मित्रावरुणा।नासत्या।द्यावा।होत्राय।पृथिवी इति।ववृत्याः।

त्वं।होता।मंद्रऽतमः।नः।अध्रुक्।अंतः।देवः।विदथा।मर्त्येषु।पावकया।जुह्वा।वह्निः।आसा।अग्ने।यज ७०

© Dharmartha Trust J&K. Digitized by eGangotri

स्वा।तन्वं।तव।स्वां।धन्या।चित्।हि।त्वेइति।धिषणा।वष्टि।प्र।देवान्।जन्म।गृणते।यजध्यै।वेपिष्ठः।
अंगिरसां।यत्।ह।विप्रः।मधु।छंदः।भनति।रेभः।इष्टौ।अदिद्युतत्।सु।अपाकः।विभाऽवा।अग्ने।य
जस्व।रोदसीइति।उरूचीइति।आयुं।न।यं।नमसा।रातऽहव्याः।अंजंति।सुऽप्रयसं।पंच।जनाः।वृंजे
ह।यत्।नमसा।बर्हिः।अग्नौ।अयामि।स्रुक्।घृतऽवती।सुऽवृक्तिः।अम्यक्षि।सद्म।सदने।पृथि
व्याः।अश्रायि।यज्ञः।सूर्ये।न।चक्षुः।दशस्य।नः।पुरुऽअनीक।होतरिति।देवेभिः।अग्ने।अग्निऽभिः।इधा
नः।रायः।सूनोइति।सहसः।ववसानाः।अति।स्रसेम।वृजनं।न।अंहः॥३॥मध्ये।होता।दुरोणे।ब
र्हिषः।राट्।अग्निः।तोदस्य।रोदसीइति।यजध्यै।अयं।सः।सूनुः।सहसः।ऋतऽवा।दूरात्।सूर्यः।न।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰य॰ ७१

71

शोचिषा।ततनाना।आ।यस्मिन्।त्वेइति।सु।अपाके।यजत्र।यक्षत्।राजन्।सर्वताताऽइव।नु।द्यौः।त्रिऽ
सधऽस्थः।तनूऽरुचः।न।जंहः।हव्या।मघानि।मानुषा।यजध्यै।ते।जिह्वा।यस्य।अरतिः।वनेऽराट्।तोदः।
अध्वन्।न।रघुऽसानः।अद्योत्।अद्रोघः।न।द्रविता।चेतति।त्मन्।अमर्त्यः।अवर्त्रः।ओषधीषु।सः।अ
स्माकेभिः।एतरि।न।शूषैः।अग्निः।स्तवे।दमे।आ।जातऽवेदाः।द्रुऽअन्नः।वन्वन्।क्रत्वा।न।अर्वा।उस्रः
।पिताऽइव।जारयायि।यज्ञैः।अध।स्म।अस्य।पनयन्ति।भासः।वृथा।यत्।तक्षत्।अनुऽयाति।पृथ्वी।
सद्यः।यः।स्पन्द्रः।विऽसितः।धवीयान्।ऋणः।न।तायुः।अति।धन्व।राट्।सः।त्वं।नः।अर्वन्।निदायाः।
विश्वेभिः।अग्ने।अग्निऽभिः।इधानः।वेषि।रायः।वि।यासि।दुच्छुनाः।०।।३धा।त्वत्।विश्वा।सुऽभगा।सौभ ७३

© Dharmartha Trust J&K. Digitized by eGangotri

गानि। अग्ने। वि। यंति। वनिनः। न। वयाः। श्रुष्टी। रयिः। वाजः। वृत्रऽतूर्ये। दिवः। वृष्टिः। ईड्यः। रीतिः। अपां। त्वं।
भगः। नः। आ। हि। रत्नं। इषे। परिज्माऽइव। क्षयसि। दस्मऽवर्चाः। अग्ने। मित्रः। न। बृहतः। ऋतस्य। असि।
क्षत्ता। वामस्य। देव। भूरेः। सः। सत्ऽपतिः। शवसा। हंति। वृत्रं। अग्ने। विप्रः। वि। पणेः। भर्ति। वाजं। यं। त्वं।
प्रऽचेतः। ऋतऽजात। राया। सऽजोषाः। नप्त्रा। अपां। हिनोषि। यः। ते। सूनो इति। सहसः। गीःऽभिः। उक्थैः।
यज्ञैः। मर्तः। निऽशितिं। वेद्या। आनट्। विश्वं। सः। देव। प्रति। वा। अरं। अग्ने। धत्ते। धान्यं। पत्यते। वसव्यैः।
ता। नृऽभ्यः। आ। सौश्रवसा। सुऽवीरा। अग्ने। सूनो इति। सहसः। पुष्यसे। धाः। कृणोषि। यत्। शवसा। भू
रि। पश्वः। वयः। वृकाय। अरये। जसुरये। वद्मा। सूनो इति। सहसः। नः। विऽहायाः। अग्ने। तोकं। तनयं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. वाजिनः।द्रः।विश्वाभिः।गीःऽभिः।अभि।पूर्तिं।अश्यां।७।१५।अग्ना।यः।मर्तः।दुवः।धियं।जुजोष।

७२ धीतिऽभिः।भसत्।नु।सः।प्र।पूर्व्यः।इषं।वुरीत।अवसे।अग्निः।इत्।हि।प्रऽचेताः।अग्निः।वेधःऽतमः।

72 ऋषिः।अग्निं।होतारं।ईळते।यज्ञेषु।मनुषः।विशः।नाना।हि।अग्ने।अवसे।स्पर्धंते।रायः।अर्यः।तूर्वंतः।

दस्युं।आयवः।व्रतैः।सीक्षंतः।अव्रतं।अग्निः।अप्सां।ऋतिऽसहं।वीरं।ददाति।सत्ऽपतिं।यस्य।त्रसंति।

शवसः।संऽचक्षि।शत्रवः।भिया।अग्निः।हि।विद्मना।निदः।देवः।मर्तं।उरुष्यति।सहऽवा।यस्य।अवृतः।

रयिः।वाजेषु।अवृतः।७।१६।इमं।ऊं।इति।सु।वः।अतिथिं।उषःऽबुधं।विश्वासां।विशां।पतिं।ऋंजसे। ७२

गिरा।वेति।इत्।दिवः।जनुषा।कत्।चित्।आ।शुचिः।ज्योक्।चित्।अत्ति।गर्भः।यत्।अच्युतं।मित्रं।न।

© Dharmartha Trust J&K. Digitized by eGangotri

यं। सुऽधितं। भृगवः। दधुः। वनस्पतौ। ईड्यं। ऊर्ध्वऽशोचिषं। सः। त्वं। सुऽप्रीतः। वीतऽहव्ये। अद्भुत। प्रशस्ति-
ऽभिः। महयसे। दिवेऽदिवे। सः। त्वं। दक्षस्य। अवृकः। वृधः। भूः। अर्यः। परस्य। अंतरस्य। तरुषः। रायः। सूनो
इति। सहसः। मर्त्येषु। आ। छर्दिः। यच्छ। वीतऽहव्याय। सऽप्रथः। भरत्ऽवाजाय। सऽप्रथः। द्युतानं। वः। अति-
थिं। स्वःऽनरं। अग्निं। होतारं। मनुषः। सुऽअध्वरं। विप्रं। न। द्युक्षऽवचसं। सुवृक्तिऽभिः। हव्यऽवाहं। अरतिं।
देवं। ऋंजसे। पावकया। यः। चितयंत्या। कृपा। क्षामन्। रुरुचे। उषसः। न। भानुना। तूर्वन्। न। यामन्। ए-
तशस्य। नु। रणे। आ। यः। घृणे। न। ततृषाणः। अजरः॥१७॥ अग्निंऽअग्निं। वः। संऽइधा। दुवस्यत। प्रियंऽप्रि- स्म
यं। वः। अतिथिं। गृणीषणि। उप। वः। गीःऽभिः। अमृतं। विवासत। देवः। देवेषु। वनते। हि। वार्यं। देवः। देवेषु।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ब॰ व नेते। हि। नः। दुवः। सं ऽ इध्रं। अग्निं। सं ऽ इधा। गिरा। गृणे। शुचिं। पावकं। पुरः। अध्वरे। ध्रुवं। विप्रं। होतारं।

७३ पुरु ऽ वारं। अद्रुहं। कविं। सुम्नैः। ईमहे। जात ऽ वेदसं। त्वां। दूतं। अग्ने। अमृतं। युगे ऽ युगे। हव्य ऽ वाहं। दधिरे। पा

73 युं। ईड्यं। देवासः। च। मर्तासः। च। जागृविं। विभुं। विश्पतिं। नमसा। नि। सेदिरे। वि ऽ भूषन्। अग्ने। उभयान्।

अनु। व्रता। दूतः। देवानां। रजसी इति। सं। ईयसे। यत्। ते। धीतिं। सु ऽ मतिं। आ ऽ वृणीमहे। अध। स्म। नः। त्रि ऽ

वरूथः। शिवः। भव। तं। सु ऽ प्रतीकं। सु ऽ दृशं। सु ऽ अञ्चं। अविद्वांसः। विदुः ऽ तरं। सपेम। सः। यक्षत्। विश्वा।

वयुनानि। विद्वान्। प्र। हव्यं। अग्निः। अमृतेषु। वोचत्। ॥ ३ ॥ तं। अग्ने। पास्यि। उत। तं। पिपर्षि। यः। ते। आन

ट्। कवये। शूर। धीतिं। यज्ञस्य। वा। निः ऽ शितिं। वा। उत् ऽ इतिं। वा। तं। इत्। पृणक्षि। शवसा। उत। राया। त्वं। ७३

© Dharmartha Trust J&K. Digitized by eGangotri

अग्ने।वनुष्यतः।नि।पाहि।त्वं।ऊं इति।नः।सहसाऽवन्।अवद्यात्।सं।त्वा।ध्वस्मन्ऽवत्।अभि।एतु।पाथः
।सं।रयिः।स्पृहयाय्यः।सहस्री।अग्निः।होता।गृहऽपतिः।सः।राजा।विश्वा।वेद।जनिम।जातऽवेदाः।दे
वानां।उत।यः।मर्त्यानां।यजिष्ठः।सः।आ।यजतां।ऋतऽवा।अग्ने।यत्।अद्य।विशः।अध्वरस्य।होतरिति
।पावकऽशोचे।वेः।त्वं।हि।यज्वा।ऋता।यजासि।महिना।वि।यत्।भूः।हव्या।वह।यविष्ठ।या।ते।अद्य।अभि
।प्रयांसि।सुऽधिता।नि।हि।ख्यः।नि।त्वा।दधीत।रोदसी इति।यजध्यै।अव।नः।मघऽवन्।वाजऽसातौ।अ
ग्ने।विश्वानि।च।१३।अग्ने।विश्वेभिः।सुऽअनीक।देवैः।ऊर्णाऽवंतं।प्रथमः।सीद।योनिं।कुलायिनं।घृत
ऽवंतं।सवित्रे।यज्ञं।नय।यजमानाय।साधु।इमं।ऊं इति।त्वां।अथर्वऽवत्।अग्निं।मंथंति।वेधसः।यं।अंकु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ षे॰ ऽयंतं। आ। अनयन्। अमूरं। श्याव्याभ्यः॥ जनिष्व। देवऽवीतये। सर्वऽताता। स्वस्तये। आ। देवान्। वक्षि। अमृ
७४ तान्। ऋतऽवृधः। यज्ञं। देवेषु। पिस्पृशः॥ वयं। ऊं इति। त्वा। गृहऽपते। जनानां। अग्ने। अकर्म। संऽइधा। बृहं
74 तं। अस्थूरि। नः। गार्हऽपत्यानि। संतु। तिग्मेन। नः। तेजसा। सं। शिशाधि॥ २१॥ त्वं। अग्ने। यज्ञानां। होता।
विश्वेषां। हितः। देवेभिः। मानुषे। जने॥ सः। नः। मंद्राभिः। अध्वरे। जिह्वाभिः। यज। महः॥ १॥ वेस्थ। हि। वेधः।
अध्वनः। पथः। च। देव। अंजसा। अग्ने। यज्ञेषु। सुक्रतो इति सुऽक्रतो॥ त्वां। ईळे। अध। द्विता। भरतः। वाजिऽभिः।
शुनं। ईजे। यज्ञेषु। यज्ञियं॥ त्वं। इमा। वार्या। पुरु। दिवःऽदासाय। सुन्वते। भरत्ऽवाजाय। दाशुषे॥ २३॥ त्वं। दूतः।
अमर्त्यः। आ। वह। दैव्यं। जनं॥ शृण्वन्। विप्रस्य। सुऽस्तुतिं॥ त्वां। अग्ने। सुऽआध्यः। मर्तासः। देवऽवीतये। य ७४

© Dharmartha Trust J&K. Digitized by eGangotri

ऽपुरःऽएवं । ईळे । नेता । तव । अग्ना । यक्षि । स्वं । दशं । उत । क्रतुं । सुऽदानवः । विश्वे । जुषंत । कामिनः । त्वं । होता । मनुःऽहितः ।
वह्निः । आसा । विदुःऽतरः । अग्ने । यक्षि । दिव्यः । विशः । अग्ने । आ । याहि । वीतये । गृणानः । हव्यऽदातये । नि । हो
ता । सत्सि । बर्हिषि ॥ २१ ॥ तं । त्वा । समित्ऽभिः । अंगिरः । घृतेन । वर्धयामसि । बृहत् । शोच । यविष्ठ्य । सः
नः । पृथु । श्रवाय्यं । अच्छ । देव । विवाससि । बृहत् । अग्ने । सुऽवीर्यं । त्वां । अग्ने । पुष्करात् । अधि । अथर्वा । निः ।
अमंथत । मूर्ध्नः । विश्वस्य । वाघतः । तं । ऊं इति । त्वा । दध्यङ् । ऋषिः । पुत्रः । ईधे । अथर्वणः । वृत्रऽहनं । पुरंऽद
रं । पाथ्यः । वृषा । सं । ईधे । दस्युहन्ऽतमं । धनंऽजयं । रणेऽरणे ॥ २२ ॥ आ । इहि । ऊं इति । सु । ब्रवाणि । ते । अग्ने
इत्था । इतराः । गिरः । एभिः । वर्धासे । इंदुऽभिः । यत्र । क्व । च । ते । मनः । दक्षं । दधसे । उत्ऽतरं । तत्र । सदः । कृणवसे ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प॰ नहि । ते । पूर्तं । अक्षिऽपत् । भुवत् । नेमानां । वसो इति । अथ । दुवः । वनवसे । आ ॥ अग्निः । अगामि । भारतः । वृ
७५ त्रहा । पुरुऽचेतनः । दिवः । दासस्य । सत्ऽपतिः ॥ सः । हि । विश्वा । अति । पार्थिवा । रयिं । दाशत् । महिऽत्वना । वन्व
75 न् । अवातः । अस्तृतः ॥ २४ ॥ सः । प्रत्नऽवत् । नवीयसा । अग्ने । द्युम्नेन । संऽयता । बृहत् । ततंथ । भानुना ॥ प्र । वः ।
सखायः । अग्नये । स्तोमं । यज्ञं । च । धृष्णुऽया । अर्च । गाय । च । वेधसे ॥ सः । हि । यः । मानुषा । युगा । सीदत् । हो
ता । कविऽक्रतुः । दूतः । च । हव्यऽवाहनः । ता । राजाना । शुचिऽव्रता । ० । वसो इति । यक्षि । इह । रोद इति । वस्वी । सी
ते । अग्ने । सं । इष्टिऽभिः । इषः । यंते । मर्त्याय । ऊर्जः । नपात् । अमृतस्य ॥ २५ ॥ क्रत्वा । दाः । अस्तु । श्रेष्ठः । अद्य । त्वा । व
न्वन् । सुऽरेक्णाः । मर्तः । आनाश । सुऽशस्तिं । ते । ते । अग्ने । त्वाऽऊताः । इषयंतः । विश्वा । आयुः । तरंतः । अर्यः । अ ७५

© Dharmartha Trust J&K. Digitized by eGangotri

रातीः । बब्धे॑ऽनः । अर्यः । अरातीः । अग्निः । तिग्मेन । शोचिषा । यासत् । विश्वं । नि । अत्रिणं । अग्निः । वनते । र नः ।
यिं । सुऽवीरं । रयिं । आ । भर । जातऽवेदः । विऽचर्षणे । जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो । त्वं । नः । पाहि ।
अंहसः । जातऽवेदः । अघऽयतः । रक्ष । नः । ब्रह्मणः । कवे । रदा । यः । नः । अग्ने । दुःऽएवः । आ । मर्तः । वधाय
दाशति । तस्मात् । नः । पाहि । अंहसः । त्वं । नः । देव । जिह्वया । परि । बाधस्व । दुःऽकृतं । मर्तः । यः । नः । जिघां
सति । भरतऽवाजाय । सः । प्रथः । शर्म । यच्छ । सहंस्य । अग्ने । वरेण्यं । वसु । अग्निः । वृत्राणि । जंघनत् । द्रविण
स्युः । विपन्यया । सम्ऽइद्धः । शुक्रः । आऽहुतः । गर्भे । मातुः । पितुः । पिता । विऽदिद्युतानः । अक्षरे । सीदन् । ऋ
तस्य । योनिं । आ । रग । ब्रह्म । प्रजाऽवत् । आ । भर । जातऽवेदः । विऽचर्षणे । अग्ने । यत् । दीदयत् । दिवि ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ षं॰ उप। त्वा। रण्वऽसंदृशं। प्रयस्वंतः। सहःऽकृत। अग्ने। ससृज्महे। गिरः। उप। छायांऽइव। घृणेः। अगन्म

७६ । शर्म। ते। वयं। अग्ने। हिरण्यऽसंदृशः। यः। उग्रःऽइव। शर्यऽहा। तिग्मऽशृंगः। न। वंसगः। अग्ने। पुरः।

रुरोजिथ। आ। यं। हस्ते। न। खादिनं। शिशुं। जातं। न। बिभ्रति। विशां। अग्निं। सुऽअध्वरे। ।२०। प्र।

76 देवं। देवऽवीतये। भरत। वसुवित्ऽतमं। आ। स्वे। योनौ। नि। सीदतु। आ। जातं। जातऽवेदसि। प्रियं।

शिशीत। अतिथिं। स्योने। आ। गृहऽपतिं। अग्ने। युक्ष्व। हि। ये। तव। अश्वासः। देव। साधवः। अरं।

वहंति। मन्यवे। अच्छ। नः। याहि। आ। वह। अभि। प्रयांसि। वीतये। । उत्। अग्ने। भारत। द्युऽमत्। अ

जस्रेण। दविद्युतत्। शोच। वि। भाहि। अजर। ।२१। वीती। यः। देवं। मर्तः। दुवस्येत्। अग्निं। ईळीत। ७६

© Dharmartha Trust J&K. Digitized by eGangotri

अध्वरे। हविष्मान्। होतारं। ससऽयजैं। रोदस्योः। उत्तानऽहस्तः। नमसा। आ। विवासेत्। ●। हृदा। तष्टं। भरा
मसि। ते। ते। भवंतु। उक्षणः। ऋषभासः। वशाः। उत। अग्निं। देवासः। अग्रियं। इंधते। वृत्रहन्ऽतमं। येन। वसू
नि। आऽभृता। तृह्ळा। रक्षांसि। वाजिना॥ ८॥ इति चतुर्थाष्टके पंचमोऽध्यायः॥ ॐ म्॥ ॥ पिबपंचोनैंद्रं मनुत्रैष्टु
भं। द्विपदांतेन पुरुहन्मा हासमोनायोनविपिमोविराकिमाउ द्वादशान चम्येकादश्यो वैश्वदेव्यौ पल्कए
कादशास्तु नइद्दशाद्वषा याते न नश्रुधी नो ष्टौ किमस्यां। ध्या चाय मानस्या ध्यावर्त्तिनो दान स्तुति रागाबो
गव्यं द्विती ये इंद्री चौत्यश्च पादौं स्यानुष्टुप् जागतस्त्र चो द्विती यादिः॥ ॐ म्॥ पिब। सोमं। अभि। यं। उग्र। त
र्दः। ऊर्वं। गव्यं। महि। गृणानः। इंद्र। वि। यः। धृष्णो इति। वधिषः। वज्रऽहस्त। विश्वा। वृत्रं। अमित्रिया। श

ते

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ वेःऽभिः। सः। ई। पाहि। यः। ऋजीषी। तरुत्रः। यः। शिप्रऽवान्। वृषभः। यः। मतीनां। यः। गोत्रऽभित्। वज्रऽभृ
७७ त्। यः। हरिऽस्थाः। सः। इंद्र। चित्रान्। अभि। तृंधि। वाजान्। एव। पाहि। प्रत्नऽथा। मंदतु। त्वा। श्रुधि। ब्रह्म
। ववृधस्व। उत। गीःऽभिः। आविः। सूर्यं। कृणुहि। पीपिहि। इषः। जहि। शत्रून्। अभि। गाः। इंद्र। तृंधि। ते। त्वा
। मदाःऽबृहत्। इंद्र। स्वधाऽवः। इमे। पीताः। उक्षयंत। द्युऽमंतं। महां। अनूनं। तवसं। विऽभूतिं। मत्सरासः
जर्हृषंत। प्रऽसहं। येभिः। सूर्यं। उषसं। मंदसानः। अवासयः। अप। दृळ्हानि। दर्द्रत्। महां। अद्रिं। परि। गा
ः। इंद्र। सतं। नुथाः। अच्युतं। सदसः। परि। स्वात्॥१॥ तव। क्रत्वा। तव। तत्। दंसनाभिः। आमासु। पक्वं।
शच्या। नि। दीधः। अपोर्णोः। दुरः। उस्रियाभ्यः। वि। दृळ्हा। उत्। ऊर्वात्। गाः। असृजः। अंगिर ७७

77

स्वानात् । पप्राथ । क्षां । महि । दंसः । वि । उर्वीं । उप । द्यां । ऋष्वः । बृहत् । इंद्र । स्तभायः । अधारयः । रोदसी इति । देव
पुत्रे इति देवऽपुत्रे । प्रत्ने इति । मातरा । यह्वी इति । ऋतस्य । अध । त्वा । विश्वे । पुरः । इंद्र । देवाः । एकं । तवसं । द
धिरे । भराय । अदेवः । यत् । अभि । औहिष्ट । देवान् । स्वःऽसाता । वृणते । इंद्रं । अत्र । अध । द्यौः । चित् । ते ।
अप । सा । नु । वज्रात् । द्विता । अनमत् । भियसा । स्वस्य । मन्योः । अहिं । यत् । इंद्रः । अभि । ओहसानं । नि
। चित् । विश्वऽआयुः । शयथे । जघान । अध । त्वष्टा । ते । महः । उग्र । वज्रं । सहस्रऽभृष्टिं । ववृतत् । शतऽअ
श्रिं । निःऽकामं । अरऽमनसं । येन । नवंतं । अहिं । सं । पिणक् । ऋजीषिन् । वर्धान् । यं । विश्वे ।
मरुतः । सऽजोषाः । पचत् । शतं । महिषान् । इंद्र । तुभ्यं । पूषा । विष्णुः । त्रीणि । सरांसि । धावन् । वृत्रऽह

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ नं।मदिरं।अंशुं।अस्मै।आ।क्षोदः।महि।वृतं।नदीनां।परिऽस्थितं।असृजः।ऊर्मिं।अपां।तासां।अनु।

७८ प्रऽवतः।इंद्र।पंथां।प्र।आर्दयः।नीचीः।अपसः।समुद्रं।एव।ता।विश्वा।चकृऽवांसं।इंद्रं।महां।उग्रं।

अजुर्यं।सहःऽदां।सुऽवीरं।त्वा।सुऽआयुधं।सुऽवज्रं।आ।ब्रह्म।नव्यं।अवसे।ववृत्यात्।सः।नः।वा

78 जाय।श्रवसे।इषे।च।राये।धेहि।द्युऽमतः।इंद्र।विप्रान्।भरत्ऽवाजे।नृऽवतः।इंद्र।सूरीन्।दिवि।च।

स्म।एधि।पार्ये।नः।इंद्र।अया।वाजं।देवऽहितं।सनेम।॥३॥अभिभूतिऽओजाः।वन्वन्।अवातः।पु

रुऽहूतः।इंद्रः।अषाळ्हं।उग्रं।सहमानं।आभिः।गीःऽभिः।वर्ध।वृषभं।चर्षणीनां।सः।युध्मः।सत्वा।

खजऽकृत्।समत्ऽवा।तुविऽम्रक्षः।नदनुऽमान्।ऋजीषी।बृहत्ऽरेणुः।च्यवनः।मानुषीणां।एकः। ७८

© Dharmartha Trust J&K. Digitized by eGangotri

रुष्टीनां।अभ भवत्।सहः।वो।सोहा।त्रा।सत्रा।अदमयः।दस्यून्।एकः।कृष्टीः।अवनोः।आर्याय।अस्ति
।स्वित्।नु।वीर्यं।तत्।ते।इंद्र।न।स्वित्।अस्ति।तत्।ऋतुऽथा।वि।वोचः।सत्।इत्।हि।ते।तुविऽजातस्य।
मन्ये।सहः।सहिष्ठ।तुरतः।तुरस्य।उग्रं।उग्रस्य।तवसः।तवीयः।अरध्रस्य।रध्रऽतुरः।बभूव।तत्।न।
ऋतं।सत्यं।अस्तु।युष्मे।इति।इत्था।वदत्ऽभिः।वलं।अंगिरःऽभिः।हन्।अच्युतऽच्युत्।दस्म।इषयंतं।
ऋण्वोः।पुरः।वि।दुरः।अस्य।विश्वाः।धाः।सः।हि।धीभिः।हव्यः।अस्ति।उग्रः।ईशानऽकृत्।महति।वृ
त्रऽतूर्ये।सः।तोकः।साता।तनये।सः।वज्री।वितंतसाय्यः।अभवत्।समत्ऽसु।सः।मज्मना।जनिम
मानुषाणां।अमर्त्येन।नाम्ना।अति।प्र।सर्स्रे।सः।द्युम्नेन।सः।शवसा।उत।राया।सः।वीर्येण।नृऽत

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ मः। संऽओकाः। सऽनयः। न। मुहे। न। मिथु। जनः। भूत्। सुऽमंतुऽनामा। चुमुरिं। धुनिं। च। वृणक्। पिप्रुं। शं

७० बरं। शुष्णं। इंद्रः। पुरां। च्यौत्नाय। शयथाय। नु। चित्॥ उत्ऽअवता। त्वक्षसा। पन्यसा। च। वृत्रऽहत्याय।

79 रथं। इंद्र। तिष्ठ। धिष्व। वज्रं। हस्ते। आ। दक्षिणऽत्रा। अभि। प्र। मंद। पुरुऽदत्र। मायाः। अग्निः। न। शुष्कं। व

नं। इंद्र। हेतिः। रक्षः। नि। धक्षि। अशनिः। न। भीमा। गंभीरया। ऋष्वया। यः। रुरोज। अध्वनयत्। दुःऽइता

। दंभयत्। च॥५॥ आ। सहस्रं। पथिऽभिः। इंद्र। राया। तुविऽद्युम्न। तुविऽवाजेभिः। अर्वाक्। याहि। सूनो

इति। सहसः। यस्य। नु। चित्। अदेवः। ईशे। पुरुऽहूत। योतोः॥ प्र। तुविऽद्युम्नस्य। स्थविरस्य। घृष्वेः। दिवः।

ररप्शे। महिमा। पृथिव्याः। न। अस्य। शत्रुः। न। प्रतिऽमानं। अस्ति। न। प्रतिऽस्थिः। पुरुऽमायस्य। सह्योः॥ ७९

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा।नुत्ना।नो।अपाकरणं।कृतं।भूत्।कुत्सं।आयुं।अतिथिऽग्वं।अस्मै।पुरु।सहस्रा।नि।शिशाः।अभि।
क्षां।उत्।तूर्वयाणं।धृषता।निनेथ।अनु।त्वा।अहिऽघ्ने।अध।देव।देवाः।मदन्।विश्वे।कविऽतमं।क
वीनां।करः।यत्र।वरिवः।बाधिता।या।द्विवा।सना।या।तन्वा।गृणानः।अनु।द्यावापृथिवी इति।नत्।ते।ओ
जः।अमर्त्यः।जिहते।इंद्र।देवाः।कृष्व।कृत्नो इति।अकृतं।यत्।ते।अस्ति।उक्थ्यं।नवीयः।जनय।यज्ञ।
यज्ञैः।दा।महान्।इंद्रः।नृऽवत्।आ।चर्षणिऽप्राः।उत।द्विऽबर्हाः।अमिनः।सहःऽभिः।अस्मद्र्यक्
वरृधे।वीर्याय।उरुः।पृथुः।सुऽकृतः।कर्तृऽभिः।भूत्।इंद्रं।एवा।धिषणा।सातये।धात्।बृहंतं।ऋ
ष्वं।अजरं।युवानं।अषाळ्हेन।शवसा।शूशुऽवांसं।सद्यः।चित्।यः।वावृधे।असामि।पृथु इति।क

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चं॰ रस्मा। बृहत्। गभस्तिऽइति। अस्मभ्यं। सं। मिमीहि। श्रवांसि। यूथाऽइव। पश्वः। पशुऽ
८ पाः। दमूनाः। अस्मान्। इंद्र। अभि। आ। ववृत्स्व। आजौ। नः। इंद्र। वनिनः। अस्य। शाकैः।
इह। नूनं। वाजऽयंतः। हुवेम। यथा। चित्। पूर्वे। जरितारः। आसुः। अनेद्यः। अनवद्यः। अ
रिष्टः। धृतऽव्रतः। धनऽदाः। सोमऽवृद्धः। सः। हि। वामस्य। वसुनः। पुरुऽक्षुः। सं। जग्मि
राः। पथ्याः। रायः। अस्मिन्। समुद्रे। न। सिंधवः। यादमानाः॥ ७॥ शविष्ठं। नः। आ। भर।
शूर। शवः। ओजिष्ठं। ओजः। अभिऽभूते। उग्रं। विश्वा। द्युम्ना। वृष्ण्या। मानुषाणां। अ
स्मभ्यं। दाः। हरिऽवः। मादयध्यै। यः। ते। मदः। पृतनाषाट्। अमृध्रः। इंद्र। तं। नः। आ। भर। ८०

© Dharmartha Trust J&K. Digitized by eGangotri

ऋभ्वऽवांसं। येन। तोकस्य। तनयस्य। सातौ। मंसीमहि। जिगीवांसः। त्वाऽऊताः। आ। नः। भर।
वृषणं। शुष्मं। इंद्र। धनऽस्पृतं। शूशुवांसं। सुऽदक्षं। येन। वंसाम। पृतनासु। शत्रून्। तव। ऊति
ऽभिः। उत। जामीन्। अजामीन्। आ। नः। शुष्मः। वृषभः। एतु। पश्चात्। आ। उत्तरात्। अधरात्।
आ। पुरस्तात्। आ। विश्वतः। अभि। सं। एतु। अर्वाङ्। इंद्र। द्युम्नं। स्वःऽवत्। धेहि। अस्मे इति। नृऽ
वत्। ते। इंद्र। नृऽतमाभिः। ऊती। वंसीमहि। वामं। श्रोमतेभिः। ईक्षे। हि। वस्वः। उभयस्य। राजन्।
धाः। रत्नं। महि। स्थूरं। बृहंतं। [illegible] ०। जनं। वज्रिन्। महि। चित्। मन्यमानं। एभ्यः। नृऽभ्यः।
रंधय। येषु। अस्मि। अध। हि। त्वा। पृथिव्यां। शूरऽसातौ। हवामहे। तनये। गोषु। अप्ऽसु। वये।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. ते । एभिः । पुरुऽहूत । सख्यैः । शत्रोःऽशत्रोः । उत्ऽतरे । इत् । स्याम । घ्नंतः । वृत्राणि । उभयानि । शूर । राया । म
८१ देम । बृहता । त्वाऽऊताः ॥ ८ ॥ द्यौः । न । यः । अभि । इंद्र । भूम । अर्यः । तस्थौ । रयिः । शवसा । पृत्ऽसु । जनान् ।
तं । नः । सहस्रऽभरं । उर्वराऽसां । दद्धि । सूनो इति । सहसः । वृत्रऽतुरं । दिवः । न । तुभ्यं । अनु । इंद्र । सत्रा । असुर्यं
। देवेभिः । धायि । विश्वं । अहिं । यत् । वृत्रं । अपः । वव्रिऽवांसं । हन् । ऋजीषिन् । विष्णुना । सचानः । तूर्वन् । ओ
जीयान् । तवसः । तवीयान् । कृतऽब्रह्मा । इंद्रः । वृद्धऽमहाः । राजा । अभवत् । मधुनः । सोम्यस्य । विश्वासां ।
यत् । पुरां । दर्त्नुं । आवत् । शतैः । अपद्रन् । पणयः । इंद्र । अत्र । दशऽओणये । कवये । अर्कऽसातौ । वधैः । शुष्ण
स्य । अशुषस्य । मायाः । पित्वः । न । अरिरेचीत् । किं । चन । प्र । महः । द्रुहः । अप । विश्वऽआयु । धायि । वज्रस्य । ८१

यत्।पतन्।नो।पादि।शुष्णः।गुरुः।सः।सुऽरथः।सारथये।कः।इंद्रः।कुत्साय।सूर्यस्य।सातौ॥५॥प्र।श्येनः।न
।मदिरं।अंशुं।अस्मै।शिरः।दासस्य।नमुचेः।मथायन्।प्र।आवत्।नमीं।साप्यं।ससंतं।पृणक्।राया।
सं।इषा।सं।स्वस्ति॥६॥वि।पिप्रोः।अहिऽमायस्य।दृळ्हाः।पुरः।वज्रिन्।शवसा।न।दर्दरिति।दर्दः।सुऽदाम
न्।तत्।रेक्णः।अप्रऽमृष्यं।ऋजिश्वने।दात्रं।दाशुषे।दाः॥७॥सः।वेतसुं।दशऽमायं।दशऽओणिं।तूतुजिं।इं
द्रः।स्वभिष्टिऽसुम्नः।आ।तुग्रं।शश्वत्।इभं।द्योतनाय।मातुः।न।सीं।उप।सृज।इयध्यै॥८॥सः।ईं।स्पृधः।व
नते।अप्रतिऽइतः।बिभ्रत्।वज्रं।वृत्रऽहनं।गभस्तौ।तिष्ठत्।हरी इति।अधि।अस्ताऽइव।गर्ते।वचःऽयुजा
वहतः।इंद्रं।ऋष्वं॥९॥सनेम।ते।अवसा।नव्यः।इंद्र।प्र।पूरवः।स्तवंते।एना।यज्ञैः।सप्त।यत्।पुरः।शर्म।शार

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ दीः । दर्त् । हन् । दासीः । पुरुऽकुत्साय । शिक्षन् ॥ त्वं । वृधः । इंद्र । पूर्व्यः । भूः । वरिवस्यन् । उशने । काव्याय । परा ।
८२ नवऽवास्त्वं । अनुऽदेयं । महे । पित्रे । ददाथ । स्वं । नपातं ॥०॥ तव । ह । त्यत् । इंद्र । विश्वं । आजौ । सस्तः । धुनी
चुमुरी इति । या । ह । सिस्वप् । दीदयत् । इत् । तुभ्यं । सोमेभिः । सुन्वन् । दभीतिः । इध्मऽभृतिः । पक्थी । अ
र्कैः ॥ ६ ॥०॥ इमाः । ऊं इति । त्वा । पुरुऽतमस्य । कारोः । हव्यं । वीर । हव्याः । हवंते । धियः । रथेऽस्थां । अजरं । न
वीयः । रयिः । विऽभूतिः । ईयते । वचस्या ॥०॥ यः । विदानः । गिर्वाहसं । गीःऽभिः । यज्ञऽवृद्धं । यस्य । दिवं ।
अति । मह्ना । पृथिव्याः । पुरुऽमायस्य । रिरिचे । महिऽत्वं ॥ सः । इत् । तमः । अवयुनं । ततन्वत् । सूर्येण ।
वयुनऽवत् । चकार । कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षंतः । न । मिनंति । स्वधाऽवः । यः । ता । चका ८२

82

© Dharmartha Trust J&K. Digitized by eGangotri

रा।सः।कुह।स्वित्।इंद्रः।कं।आ।जने।चरति।कासु।विक्षु।कः।ते।यज्ञः।मनसे।शं।वराय।कः।अर्कः।इंद्र।क
तमः।सः।होता।इद्राः।हि।ते।वेविषतः।पुरुऽजाः।प्रत्नासः।आसुः।पुरुऽकृत्।सखायः।ये।मध्यमासः।उ
ता।नूतनासः।उत।अवमस्य।पुरुऽहूत।बोधि॥३॥ तं।पृच्छंतः।अवरासः।पराणि।प्रत्ना।ते।इंद्र।श्रुत्या।अ
नु।येमुः।अर्चीमसि।वीर।ब्रह्मऽवाहः।यात्।एव।विद्म।तात्।त्वा।महांतं।अभि।त्वा।पाजः।रक्षसः।वि।तस्थे।
महि।जज्ञानं।अभि।तत्।सु।तिष्ठ।तव।प्रत्नेन।युज्येन।सख्या।वज्रेण।धृष्णो इति।अप।ता।नुदस्व।सः।तु
श्रुधि।इंद्र।नूतनस्य।ब्रह्मण्यतः।वीर।कारुऽधायः।त्वं।हि।आपिः।प्रऽदिवि।पितॄणां।शश्वत्।बभूथ।सुऽ
हवः।आऽइष्टौ।प्र।ऊतये।वरुणं।मित्रं।इंद्रं।मरुतः।कृष्व।अवसे।नः।अर्यमा।पूषणं।विष्णुं।अग्निं।पुरंऽधिं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ सविता। ओषधीः। पर्वताः। च। इमाः। ऊं इति। त्वा। पुरुऽशाक। प्रयज्यो इति प्रऽयज्यो। जरितारः। अभि। अर्च

८३ न्ति। अर्कैः। श्रुधि। हवं। आ। हुवतः। हुवानः। न। त्वाऽवान्। अन्यः। अमृत। त्वत्। अस्ति॥ नु। मे। आ। वाचं। उप। या

८३ हि। विद्वान्। विश्वेभिः। सूनो इति। सहसः। यजत्रैः। ये। अग्निऽजिह्वाः। ऋतऽसापः। आसुः। ये। मनुं। चक्रुः। उ

परं। दसाय॥ सः। नः। बोधि। पुरःऽएता। सुऽगेषु। उत। दुःऽगेषु। पथिऽकृत्। विदानः। ये। अश्रमासः। उरवः। व

हिष्ठाः। तेभिः। नः। इंद्र। अभि। वक्षि। वाजं॥१३॥ यः। एकः। इत्। हव्यः। चर्षणीनां। इंद्रं। तं। गीःऽभिः। अभि।

अर्च। आभिः। यः। पत्यते। वृषभः। वृष्ण्यऽवान्। सत्यः। सत्वा। पुरुऽमायः। सहस्वान्। तं। ऊं इति। नः। पूर्वे। पि

तरः। नवऽग्वाः। सप्त। विप्रासः। अभि। वाजयंतः। नक्षत्ऽदाभं। ततुरिं। पर्वतेऽस्थां। अद्रोघऽवाचं। मतिऽ ८३

© Dharmartha Trust J&K. Digitized by eGangotri

भिः। शविष्ठं। नः। ईमहे। इंद्रं। अस्य। रायः। पुरुऽवीरस्य। नृऽवतः। पुरुऽक्षोः। यः। अस्कृधोयुः। अजरः। स्वःऽवान्।
तं। आ। भर। हरिऽवः। मादयध्यै। न। तत्। नः। वि। वोचः। यदि। ते। पुरा। चित्। जरितारः। आनशुः। सुम्नं। इंद्र। कः।
ते। भागः। किं। वयः। दुध्र। खिद्वः। पुरुऽहूत। पुरुवसो इति पुरुऽवसो। असुरऽघ्नः। तं। पृच्छंती। वज्रऽहस्तं। रथे
ऽस्थां। इंद्रं। वेपी। वक्वरी। यस्य। नु। गीः। तुविऽग्राभं। तुविऽकूर्मिं। रभःऽदां। गातु। इषे। नक्षते। तुम्रं। अच्छ॥ ३॥
अया। ह। त्यं। मायया। ववृधानं। मनःऽजुवा। स्वऽतवः। पर्वतेन। अच्युता। चित्। वीळिता। सुऽओजः। रुजः।
५ वि। दृळ्हा। धृषता। विरप्शिन्। तं। वः। धिया। नव्यस्या। शविष्ठं। प्रत्नं। प्रत्नऽवत्। परिऽतंसयध्यै। सः। नः। व
क्षत्। अनिऽमानः। सुऽवह्मा। इंद्रः। विश्वानि। अति। दुःऽगहानि। आ। जनाय। द्रुहणे। पार्थिवानि। दिव्या।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ नि।दीपयः।अंतरिक्षा।तपा।रष्टुना।विश्वतः।शोचिषा।तान्।ब्रह्मऽद्विषे।शोचय।क्षां।अपः।च।भुवः।जन

८४ स्य।दिव्यस्य।राजा।पार्थिवस्य।जगतः।त्वेषऽसंदृक्।धिष्व।वज्रं।दक्षिणे।इंद्र।हस्ते।विश्वाः।अजुर्य।दय

84 से।वि।मायाः।आ।संऽयतं।इंद्र।नः।स्वस्तिं।शत्रुऽतूर्याय।बृहतीं।अमृध्रां।यया।दासानि।आर्याणि।वृ

त्रा।करः।वज्रिन्।सुऽतुका।नाहुषाणि।सः।नः।नियुत्ऽभिः।पुरुऽहूत।वेधः।विश्वऽवाराभिः।आ।गहि

प्रयज्यो इति प्रऽयज्यो।न।याः।अदेवः।वरते।न।देवः।आ।आभिः।याहि।तूयं।आ।मद्र्यद्रिक्॥३४॥सुते।

इत्।त्वं।निऽमिश्लः।इंद्र।सोमे।स्तोमे।ब्रह्मणि।शस्यमाने।उक्थे।यत्।वा।युक्ताभ्यां।मघऽवन्।हरिऽ

भ्यां।बिभ्रत्।वज्रं।बाह्वोः।इंद्र।यासि।यत्।वा।दिवि।पार्ये।सुस्विं।इंद्र।वृत्रऽहत्ये।अवसि।शूरऽसातौ। ८४

© Dharmartha Trust J&K. Digitized by eGangotri

यत्।वा।दक्षस्य।बिभ्युषः।अबिभ्यत्।अरंधयः।शर्द्धतः।इंद्र।दस्यून्।पाता।सुतं।इंद्रः।अस्तु।सोमं।प्रऽनेनी

ःउग्रः।जरितारं।ऊती।कर्त्ता।वीराय।सुस्वये।ऊं इति।लोकं।दाता।वसु।स्तुवते।कीरये।चित्।गंता।इयंति।

सवना।हरिऽभ्यां।बभ्रिः।वज्रं।पपिः।सोमं।ददिः।गाः।कर्त्ता।वीरं।नर्यं।सर्वऽवीरं।श्रोता।हवं।गृणतः।स्तो

मऽवाहाः।अस्मै।वयं।यत्।ववान।तत्।विविष्मः।इंद्राय।यः।नः।प्रऽदिवः।अपः।करिति।कः।सुते।सोमे।स्तु

मसि।शंसत्।उक्था।इंद्राय।ब्रह्म।वर्धनं।यथा।असत्।।५।।ब्रह्माणि।हि।चकृषे।वर्धनानि।तावत्।ते

इंद्र।मतिऽभिः।विविष्मः।सुते।सोमे।सुतऽपाः।शंऽतमानि।रांड्या।क्रियास्म।वक्षणानि।यज्ञैः।०।पुरोका

शं।रराणः।पिब।तु।सोमं।गोऽऋजीकं।इंद्र।आ।उरु।कृधि।त्वाऽयतः।ऊं इति।लोकं।सः।मंदस्व।हि।अनु।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰चे॰ ओषं । उग्र । प्र । ता । यज्ञाः । सः । इमा । अश्रुवं । तु । प्र । इमा । हव्याः । सः । पुरु । कृतं । अस्मे । इति । आ । त्वा । इयं । धीः । अवसे

८५ । इंद्र । यम्याः । नां । वः । सरत्या । यः । सां । यथा । सुतेषु । कुवित् । तस्मै । असति । नः । भरा । या । न । सुखिं । इंद्रः । अव

सो । मध्यान्ति । एवा । इत् । इंद्रः । सुते । अस्तावि । सोमे । भरत्ऽवाजेषु । क्षयत् । इत् । मघोनः । असत् । यथा । ज

85 रित्रे । उत । सूरिः । इंद्रः । रायः । विश्वऽवारस्य । दाता ॥ १० ॥ वृषा । मदः । इंद्रे । श्लोकः । उक्था । सचा । सोमेषु

सुतऽपाः । ऋजीषी । अर्चत्र्यः । मघऽवा । नृऽभ्यः । उक्थैः । द्युक्षः । राजा । गिरां । अक्षितऽऊतिः । ततुरिः । वीरः ।

उ॰ नर्यः । विऽचेताः । श्रोता । हवं । गृणतः । उर्विऽऊतिः । वसुः । शंसः । नरां । कारुऽधायाः । वाजी । स्तुतः । विदथे । दाति

। वाजं । अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः । वृक्षस्य । नु । ते । पुरुऽहूत । वयाः । वि । ८५

© Dharmartha Trust J&K. Digitized by eGangotri

ऊतयः। ऋभुक्षाः। इंद्र। पूर्वीः। शचीऽवतः। नः। पुरुऽशाक। शाकाः। गवांऽइव। स्रुतयः। संऽचरणीः। वत्सानां। न। तंत
यः। नः। इंद्र। दामन्ऽवंतः। अदामानः। सुऽदामन्। अन्यत्। अद्य। कर्वरं। अन्यत्। ऊं इति। श्वः। असत्। च। सत्
। मुहुः। आऽचक्रिः। इंद्रः। मित्रः। नः। अत्र। वरुणः। च। पूषा। अर्यः। वशस्य। परिऽएता। अस्ति।।३७।। वि। त्वत्
आपः। न। पर्वतस्य। पृष्ठात्। उक्थेभिः। इंद्र। अनयंत। यज्ञैः। तं। त्वा। आभिः। सुस्तुतिऽभिः। वाजयंतः। आ
जिं। न। जग्मुः। गिर्वाहः। अश्वाः। न। यं। जरंति। शरदः। न। मासाः। न। द्यावः। इंद्रं। अवऽकर्शयंति। वृद्धस्य।
चित्। वर्धतां। अस्य। तनूः। स्तोमेभिः। उक्थैः। च। शस्यमाना। न। वीळवे। नमते। न। स्थिराय। न। शर्ध
ते। दस्युऽजूताय। स्तवान्। अज्राः। इंद्रस्य। गिरयः। चित्। ऋष्वाः। गंभीरे। चित्। भवति। गाधं। अस्मै। गं

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. भीरेण।नः।उरुणा।अमत्रिन्।ग्ना।इव।यं।धिया।सुतनःऽपावन्।वा।आ।न।स्था।ऊं इति।सु।ऊर्ध्वः।ऊती।अरिष
८६ ण्यन्।अक्तोः।विऽउष्टौ।परिऽतक्म्यायाः।सचस्व।ना।ये।अवसे।अभीके।इतः।वा।तं।इंद्र।पाहि।रिषः।अमा
।च।एनं।अरण्ये।पाहि।रिषः।।१०।।या।ते।ऊतिः।अवमा।या।परमा।या।मध्यमा।इंद्र।शुष्मिन्।अ
स्ति।ताभिः।ऊं इति।सु।वृत्रऽहत्ये।अवीः।नः।एभिः।च।वाजैः।महान्।नः।उग्र।आभिः।स्पृधः।मिथतीः।
अरिषण्यन्।अमित्रस्य।व्यथय।मन्युं।इंद्र।आभिः।विश्वाः।अभिऽयुजः।विषूचीः।आर्याय।विशः।
अव।तारीः।दासीः।इंद्र।जामयः।उत।ये।अजामयः।अर्वाचीनासः।वनुषः।युयुज्रे।त्वं।एषां।विथुरा।
शवांसि।जहि।वृष्ण्यानि।कृणुहि।पराचः।शूरः।वा।शूरं।वनते।शरीरैः।तनूऽरुचा।तरुषि।यत्।कृ ८६

© Dharmartha Trust J&K. Digitized by eGangotri

ण्वैते इति । तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति । नहि । त्वा । शूरः । न । तुरः । न
धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध । इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषां । विश्वा । जातानि । अभि । असि ।
तानि ॥ ३० ॥ सः । पत्यते । उभयोः । नृम्णं । अयोः । यदि । वेधसः । सम्ऽइथे । हवन्ते । वृत्रे । वा । महः । नृऽवति । क्षये । वा
व्यचस्वन्ता । यदि । वितन्तसैते इति । अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता । अस्माका
सः । ये । नृऽतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः । अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वं । अनु । वृत्र
ऽहत्ये । अनु । क्षत्रं । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृऽसह्ये । एव । नः । स्पृधः । सं । अज । समत्ऽसु । इन्द्र
ररन्धि । मिथतीः । अदेवीः ॥ ९ ॥ भरत्ऽवाजाः । उत । ते । इन्द्र । नूनं ॥ २० ॥ श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाज

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ वे॰ स्या। सा। नौ। वृषाणाः॥ सो। यन्ता। विशः॥ अयंता। शूरः। सा। नौ। उग्रं। नृः॥ अवः। पार्यै। अहन्। दृढः। त्वं। वाजी। हवते
८७ । वाजिनेयः॥ महः। वाजस्य। गध्यस्य। सातौ। त्वं। वृत्रेषु। इंद्र। सत्ऽपतिं। नरुत्रं। त्वं। चहेगुष्टिऽहा। गोषु। यु
ध्यन्। त्वं। कविं। चोदयः। अर्कऽसातौ। त्वं। कुत्साय। शुष्णं। दाशुषे। वर्क्। त्वं। शिरः। अमर्मणः। परा। अहन्। अ
87 तिथिऽग्वाय। शंस्यं। करिष्यन्। त्वं। रथं। प्र। अभरः। योधं। ऋष्वं। आवः। युध्यन्तं। वृषभं। दशऽद्युं। त्वं। तुग्रं। वेतस
वे। सचा। अहन्। त्वं। तुजिं। गृणन्तं। इंद्र। तूतोरिति। तूतोः॥ त्वं। ननः। उक्थं। इंद्र। बर्हणा। करिरिति। कः॥ प्र। अयन्। शता
। सहस्रा। शूर। दर्षि। अव। गिरेः। दासं। शंबरं। हन्। प्र। आवः। दिवःऽदासं। चित्राभिः। ऊती॥ २३॥ त्वं। श्रद्धा
भिः। मंदसानः। सोमैः। दभीतये। चुमुरिं। इंद्र। सिस्वप्। त्वं। रजिं। पिठीनसे। दशस्यन्। षष्टिं। सहस्रा। श ८१

© Dharmartha Trust J&K. Digitized by eGangotri

स्या। सचा। अहन्। अहं। यन्ना। तनू। सूरिऽभिः। आ। नरयां। नवाज्या। यः। इंद्र। सुम्नं। ओजः। त्वया। यत्न। स्तवंते। स
धऽवीर। वीराः। त्रिऽवरूथेन। नहुषा। शविष्ठ। वयं। ते। अस्यां। इंद्र। द्युम्नऽहूतौ। सखायः। स्याम। महिना। प्रेष्ठाः
ः। प्रातर्दनिः। क्षत्रऽश्रीः। अस्तु। श्रेष्ठः। घने। वृत्राणां। सनये। धनानां॥२२॥ किं। अस्य। मदे। किं। ऊं इति। अ
स्य। पीतौ। इंद्रः। किं। अस्य। सख्ये। चकार। रणाः। वा। ये। निऽसदि। किं। ते। अस्य। पुरा। विविद्रे। किं। ऊं इति।
नूतनासः। सनाः। अस्य। ०। नहि। नु। ते। महिमनः। समस्य। न। मघऽवन्। मघवन्ऽत्वस्य। विद्म। न। राधस
ःराधसः। नूतनस्य। इंद्र। नकिः। ददृशे। इंद्रियं। ते। एतत्। त्यत्। ते। इंद्रियं। अचेति। येन। अवधीः। वरऽशि
खस्य। शेषः। वज्रस्य। यत्। ते। निऽहतस्य। शुष्मात्। स्वनात्। चित्। इंद्र। परमः। ददार। वधीत्। इंद्रः। वरः

© Dharmartha Trust J&K. Digitized by eGangotri

१·५· शिखस्य। शेषः। अभिऽआवर्तिने। चायमानाय। शिक्षन्। वृचीवतः। यत्। हरिऽयूपीयायां। हन्। पूर्वे। अर्द्धे।
८८ भियसा। अपरः। दर्त्॥ ५॥ त्रिंशत्ऽशतं। वर्मिणः। इंद्र। साकं। यव्याऽवत्यां। पुरुऽहूत। श्रवस्या। वृचीवंतः। श
रवः। पत्यमानाः। पात्रा। भिंदानाः। निऽअर्थानि। आयन्। यस्य। गावौ। अरुषा। सुयवस्यू इति सुऽयवस्यू।
अंतः। ऊं इति। सु। चरंतः। रेरिहाणा। सः। संऽजयाय। तुर्वशं। परा। अदात्। वृचीवंतः। दैवऽवाताय। शिक्षन्॥ ६॥ द्व
यान्। अग्ने। रथिनः। विंशतिं। गाः। वधूऽमंतः। मघऽवा। मह्यं। संऽराट्। अभिऽआवर्ती। चायमानः। ददाति।
दुःऽनशा। इयं। दक्षिणा। पार्थवानां॥ ७॥ आ। गावः। अग्मन्। उत। भद्रं। अक्रन्। सीदंतु। गोऽस्थे। रणयं
तु। अस्मे इति। प्रजाऽवतीः। पुरुऽरूपाः। इह। स्युः। इंद्राय। पूर्वीः। उषसः। दुहानाः। इंद्रः। यज्वने। पृणते। च। शि ८८

© Dharmartha Trust J&K. Digitized by eGangotri

क्षति । उप । इत् । ददाति । न । स्वं । मुषायति । भूयःऽभूयः । रयिं । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधा
ति । देवऽयुं । न । ताः । नशंति । न । दभाति । तस्करः । न । आसां । आमित्रः । व्यथिः । आ । दधर्षति । देवान् । च । या
भिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह । न । ताः । अर्वा । रेणुऽककाटः । अश्नुते । न ।
संस्कृतऽत्रं । उप । यंति । ताः । अभि । उरुऽगायं । अभयं । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरंति । यज्वनः । गा
वः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः । इमाः । याः । गावः । इच्छामि । इत् । हृदा ।
मनसा । चित् । इंद्रं । यूयं । गावः । मेदयथ । कृशं । चित् । अश्रीरं । चित् । कृणुथ । सुऽप्रतीकं । भद्रं । गृहं । कृणुथ ।
भद्रऽवाचः । बृहत् । वः । वयः । उच्यते । सभासु । प्रजाऽवतीः । सुऽयवसे । रिशंतीः । शुद्धाः । अपः । सुऽप्रपाने ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. पिबंतीः । मा । वः । ० । परि । वः । हेतिः । रुद्रस्य । वृज्याः । उप । इदं । उपऽपर्चनं । आसु । गोषु । उप । पृच्यतां । उप । ऋषभ
८९ स्य । रेतसि । उप । इंद्र । तव । वीर्यै ॥ २५ ॥ इति चतुर्थाष्टके षष्ठोध्यायः ॥ ॥ ॐ म् ॥ इंद्र षट् भूयः पंचाभूरेकः सु
89 होत्रस्तु चतुर्थी शक्वर्यं पूर्व्याय ओजिष्ठः शुनहोत्रस्तु संचत्वे कदा नरस्तु सत्रावीगपान्त्यं द्रस्येंद्र पिबा हे कमा
नः प्रत्यस्मै चतुष्कमानुष्टुभं बृहत्यंतं पस्यो ष्णिहं यो रयिवश्चतुर्विंशतिः शंयुर्बार्हस्पत्यस्त्वामेकादशैषककनुष्टुभ
स्त्रिष्टुभिराजो मध्यमेववासौ य आनयत्त्रयस्त्रिंशद्गायत्रं पुरूतममतिनिचृद्दधिक्रबुः पादनिचृद्दंद्या
नुष्टुपत्वं चैस्ये बभ्रुस्तक्षा देवतं त्वामिद्धि षट्कूनामाग्राथं स्वादुरेकत्रिंशद्गाः पंचादौ सौम्यो गव्यूस्त्यर्धर्चौलिं
गोक्ते देवतोऽग्रस्तोकः इति त्रिष्टुबनुष्टुब्गायत्री द्विपदा साज्ञो यस्याग्रस्तोकस्यादानस्तुतिः परोतयौ रथं दु ८९

© Dharmartha Trust J&K. Digitized by eGangotri

भिदेवसावैंद्रोंसोर्धचौंयुजानोबृहतीत्रिष्टुद्विपदांदिवस्पथिव्याजगमी॥ऽ३॥ओंमा।इंद्रं।वः।नरः।स
ख्याय।सपुः।महः।यंतः।सुःमतये।चकानाः।महः।हि।दाना।वः।अः।हस्तः।अस्ति।महां।कं।इमि।रण्वं।अव
सा।पज।ध्वं।आ।यस्मिन्।हस्तो।नर्यः।मिमिक्षुः।आ।रथो।हिरण्यये।रथेः।स्तोः।आ।रश्मयः।गभस्तो।
ःस्कूरयोः।आ।अध्वन।अभ्यासः।रथणः।युजानाः।श्रिये।लो।पादो।दुवः।आ।मिमिक्षुः।धृष्णुः।वज्री
शावसा।दक्षिणः।आन।वसानः।अत्कं।सुरभिं।दृशे।कं।स्वः।नान्र।लो।इनि।इषिरः।बभूथ।सः।सोमः।
आमिश्लः।नमः।सुतः।भूता।यस्मिन्।पक्ति।पश्यलो।संलि।धानाः।इंद्रं।नरः।स्तुवंतः।ब्रह्मः।काराः।उ
क्था।शंसंतः।देववातः।नमाः।नालो।अंतः।शवसः।धायि।अस्या।बिलु।बाबधे।रोदसी।इति।महिः।वा।

© Dharmartha Trust J&K. Digitized by eGangotri

सत्यौ।

प॰ ष॰ आ। नः। सूरिः। एणानि। व्रतं। आ। नः। यूथाऽइव। अपःऽस्तुः। सं। ईजमानः। ऊती। एव। इत्था। इंद्रः। सुऽहवः। ऋष्वः। अ

१० स्तु। ऊती। अनंती। हि। रिशिप्रः। एव। हि। जातः। असमातिऽओजाः। पुरु। च। वृत्रा। हनति। नि। दस्यून्।

॥१॥ भूयः। इत्। वावृधे। वीर्याय। एकः। अजुर्यः। दयते। वसूनि। प्र। रिरिचे। दिवः। इंद्रः। पृथिव्याः। अर्धं।

इत्। अस्य। प्रति। रोदसी इति। उभे इति। अधा। मन्ये। बृहत्। असुर्यं। इंद्र। अस्य। यानि। दाधार। न। किः।

आ। मिनाति। दिवेऽदिवे। सूर्यः। दर्शतः। भूत्। वि। सद्मानि। उर्विया। सुऽक्रतुः। धात्। अद्य। चित्। नु। चि

त्। तत्। अपः। नदीनां। यत्। आभ्यः। अरदः। गातुं। इंद्र। नि। पर्वताः। अद्मऽसदः। न। सेदुः। त्वया। दृळ्हा

नि। सुक्रतो इति सुऽक्रतो। रजांसि। सत्यं। इत्। तत्। न। त्वाऽवान्। अन्यः। अस्ति। इंद्र। देवः। न। मर्त्यः। १०

© Dharmartha Trust J&K. Digitized by eGangotri

ज्यायन्त्वा। अव। असृजः। अपः। अच्छ। समुद्रं। त्वं। अपः। वि। दुरः। विषूचीः। इंद्र। दृळ्हं। अरुजः। पर्वत
स्य। राजा। अभवः। जगतः। चर्षणीनां। साकं। सूर्यं। जनयन्। द्यां। उषसं। ॥२॥ अभूः। एकः। रयिऽपते। र
यीणां। आ। हस्तयोः। अधिथाः। इंद्र। कृष्टीः। वि। तोके। अप्ऽसु। तनये। च। सूरे। अवोचंत। चर्षणयः।
विऽवाचः। त्वत्। भिया। इंद्र। पार्थिवानि। विश्वा। अच्युता। चित्। च्यवयंते। रजांसि। द्यावाक्षामा। प
र्वतासः। वनानि। विश्वं। दृळ्हं। भयते। अज्मन्। आ। ते। त्वं। कुत्सेन। अभि। शुष्णं। इंद्र। अशुषं। युध्य।
कुयवं। गोऽइष्टौ। दश। प्रऽपित्वे। अध। सूर्यस्य। मुषायः। चक्रं। अविवेः। रपांसि। त्वं। शतानि। अ
व। शंबरस्य। पुरः। जघंथ। अप्रतीनि। दस्योः। अशिक्षः। यत्र। शच्या। शचीऽवः। दिवःऽदासाय। सु

© Dharmartha Trust J&K. Digitized by eGangotri

प.वे.
२३
91

त्वेतो।सुतऽअर्कः।भरत्ऽवाजाय।गृणते।वसूनि।सः।सस्त्वन्।महते।रणाय।रथं।आ।तिष्ठ।तुवि
ऽद्युम्न।भीमं।याहि।प्रऽपथिन्।अवसा।उप।मद्रिक्।प्र।च।श्रुत।श्रवय।चर्षणिऽभ्यः।।३।।अव
स्या।पुरुऽतमानि।अस्मै।महे।वीराय।तवसे।तुराय।विऽरप्शिने।वज्रिणे।शंऽतमानि।वचांसि।
आसा।स्थविराय।तक्षं।सः।मातरा।सूर्येण।कवीनां।अवासयत्।रुजत्।अद्रिं।गृणानः।सुऽआ
धीभिः।ऋक्वऽभिः।वावशानः।उत्।उस्रियाणां।असृजत्।निऽदानं।सः।वह्निऽभिः।ऋक्वऽभिः।गोषु
।शश्वत्।मितज्ञुऽभिः।पुरुऽकृत्वा।जिगाय।पुरः।पुरःऽहा।सखिऽभिः।सखिऽयन्।दृळ्हाः।रुरोज
।कविऽभिः।कविः।सन्।सः।नीव्याभिः।जरितारं।अच्छ।महः।वाजेभिः।महत्ऽभिः।च।शुष्मैः।पु २३

© Dharmartha Trust J&K. Digitized by eGangotri

रः। वीरेभिः। वृषभ। क्षितीनां। आ। गिर्वणः। सुविताय। प्र। याहि। सः। सर्गेण। शवसा। तक्तः। अत्यैः।
अपः। इंद्रः। दक्षिणतः। तुराषाट्। इत्था। सृजानाः। अनपऽवृत्। अर्थं। दिवेऽदिवे। विविषुः। अप्रऽमृष्यं
॥४॥ यः। ओजिष्ठः। इंद्र। तं। सु। नः। दाः। मदः। वृषन्। सुऽअभिष्टिः। दास्वान्। सौवश्व्यं। यः। वनवत्।
सुऽअश्वः। युध्मा। सम्ऽअत्ऽसु। सऽसहत्। अमित्रान्। त्वां। हि। इंद्र। अवसे। विऽवाचः। हवंते। चर्षणयः। शूर
रऽसातौ। त्वं। विप्रेभिः। वि। पणीन्। अशायः। त्वाऽऊतः। इत्। सनिता। वाजं। अर्वा। त्वं। तान्। इंद्र। उभ
यान्। अमित्रान्। दासा। वृत्राणि। आर्या। च। शूर। वधीः। वनाऽइव। सुऽधितेभिः। अत्कैः। आ। पृत्ऽसु
दर्षि। नृणां। नृऽतम। सः। त्वं। नः। इंद्र। अकवाभिः। ऊती। सखा। विश्वऽआयुः। अविता। वृधे। भूः। स्वःऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ चे॰ सा।ना।यतन्।ऊ यामसि।त्वा।सुध्यंतः।नेमऽधिता।एतत्।सु।भूर।नूनं।नः।इंद्र।अपराय।च।स्याः।भव।

१२ मृळीकः।उत।नः।अभिष्टौ।इत्था।गृणंतः।महिनस्य।शर्मन्।दिवि।स्याम।पार्ये।गोसःतमाः।१५।

92

सं।च।त्वे इति।जग्मुः।गिरः।इंद्र।पूर्वीः।वि।च।त्वत्।यंति।विऽभ्वः।मनीषाः।पुरा।नूनं।च।स्तुतयः।

ऋषीणां।पस्पृध्रे।इंद्रे।अधि।उक्थऽअर्का।पुरुऽहूतः।यः।पुरुऽगूर्तः।ऋभ्वा।एकः।पुरुऽप्रशस्तः।

अस्ति।यज्ञैः।रथः।न।महे।शवसे।युजानः।अस्माभिः।इंद्रः।अनुऽमाद्यः।भूत्।न।यं।हिंसंति।

धीतयः।न।वाणीः।इंद्रं।नक्षंति।इत्।अभि।वर्धयंतीः।यदि।स्तोतारः।शतं।यत्।सहस्रं।गृणं

ति।गिर्वणसं।शं।तत्।अस्मै।अस्मै।एतत्।दिवि।अर्चाऽइव।मासा।मिमिक्षः।इंद्रे।नि।अयामि। १२

© Dharmartha Trust J&K. Digitized by eGangotri

सोमः।जनं।नापध्वन्।अभि।सं।यत्।आपः।सत्रा।ववृधुः।हवनानि।यज्ञैः।अस्मै।एतत्।महि।आं
गूषं।अस्मै।इंद्राय।स्तोत्रं।मतिऽभिः।अवाचि।~~तत्।यथा।सौमनस्या~~।असत्।यथा।महति।वृ
त्रऽतूर्ये।इंद्रः।विश्वऽआयुः।अविता।वृधः।च।भूत्।कदा।भुवन्।रथऽक्षयाणि।ब्रह्म।कदा।स्तोत्रे।स
हस्रऽपोष्यं।दाः।कदा।स्तोमं।वासयः।अस्य।राया।कदा।धियः।करसि।वाजऽरत्नाः।कर्हि।स्वित्।
तत्।इंद्र।यत्।नृऽभिः।नॄन्।वीरैः।वीरान्।नीळयासे।जय।आजीन्।त्रिऽधातु।गाः।अधि।जयासि।
गोषु।इंद्र।द्युम्नं।स्वःऽवत्।धेहि।अस्मेइति।जरित्रे।विश्वऽप्सु।ब्रह्म।कृणवः।शविष्ठ।कदा।धियः।
न।निऽयुतः।युवासे।कदा।गोऽमघा।हवनानि।गच्छाः।सः।गोऽमघाः।जरित्रे।अश्वऽचंद्राः।वाजऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ श्रवसः। अधि। धेहि। पृक्षः। पीपिहि। इषः। सुऽदुघां। इंद्र। धेनुं। भरत्ऽवाजेषु। सुऽरुचः। रुरुच्याः। तं। आ
९३ । नूनं। वृजनं। अन्यथा। चित्। शूरः। यत्। शक्र। वि। दुरः। गृणीषे। मा। निः। अरं। शुक्रऽदुघस्य। धेनोः
। आंगिरसान्। ब्रह्मणा। विप्र। जिन्व॥७॥ सत्रा। मदासः। तव। विश्वऽजन्याः। सत्रा। रायः। अध। ये
। पार्थिवासः। सत्रा। वाजानां। अभवः। विऽभक्ता। यत्। देवेषु। धारयथाः। असुर्यं। अनु। प्र। येजे। ज
नः। ओजः। अस्य। सत्रा। दधिरे। अनु। वीर्याय। स्यूमऽगृभे। दुधये। अर्वते। च। क्रतुं। वृंजंति। अपि
। वृत्रऽहत्ये। तं। सध्रीचीः। ऊतयः। वृष्ण्यानि। पौंस्यानि। निऽयुतः। सश्चुः। इंद्रं। समुद्रं। न। सिंध
वः। उक्थऽशुष्माः। उरुऽव्यचसं। गिरः। आ। विशंति। सः। रायः। खां। उप। सृज। गृणानः। पुरुऽश्चंद्र ९३

© Dharmartha Trust J&K. Digitized by eGangotri

स्य। त्वं। इंद्र। वस्वः। पतिः। बभूथ। असमः। जनानां। एकः। विश्वस्य। भुवनस्य। राजा। सः। नु। श्रुधि। श्रु
त्या। यः। दुवःऽयुः। द्यौः। न। भूम। अभि। रायः। अर्यः। असः। यथा। नः। शवसा। चकानः। युगेऽयुगे। वय
सा। चेकितानः। ॥१८॥ अर्वाक्। आ। रथं। विश्वऽवारं। ते। उग्राः। इंद्र। युक्तासः। हरयः। वहंतु। कीरिः। चित्। हि।
त्वा। हवते। स्वःऽवान्। ऋधीमहि। सधऽमादः। ते। अद्य। प्रो इति। द्रोणे। हरयः। कर्म। अग्मन्। पुनानासः।
ऋज्यंतः। अभूवन्। इंद्रः। नः। अस्य। पूर्व्यः। पपीयात्। द्युक्षः। मद[स्य]। सोम्यस्य। राजा। आऽसस्राणासः। स्य ३
शवसानं। अछ। इंद्रं। सुऽचक्रे। रथ्यासः। अश्वाः। अभि। श्रवः। ऋज्यंतः। वहेयुः। नु। चित्। नु। वायोः। अ
मृतं। वि। दस्येत्। व[रि]ष्ठः। अस्य। दक्षिणां। इयर्ति। इंद्रः। मघोनां। तुविकूर्मिऽतमः। यया। वज्रिऽवः। परि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰
९८
95

ऽस्य। असि। अंहः। मघा। च। अध्वस्मो इति। दयसे। वि। सूरीन्। इंद्रः। वाजस्य। स्थविरस्य। दाता। इंद्रः। गीःऽभि
ः। वर्धतां। वृद्धऽमहाः। इंद्रः। वृत्रा। हनिष्ठः। अस्तु। सत्वा। आ। ता। सूरिः। पृणति। तूतुजानः। ९। अपात्
इतः। उत्। ऊं इति। नः। चित्रऽतमः। महीं। भर्षत्। द्युऽमतीं। इंद्रऽहूतिं। पन्यसीं। धीतिं। दैव्यस्य। यामन्।
जनस्य। रातिं। वनते। सुऽदानुः। दूरात्। चित्। आ। वसतः। अस्य। कर्णा। घोषात्। इंद्रस्य। तन्यति। ब्रु
वाणः। आ। इयं। एनं। देवऽहूतिः। ववृत्यात्। मद्र्यक्। इंद्रं। इयं। ऋच्यमाना। तं। वः। धिया। परमया।
पुराऽजां। अजरं। इंद्रं। अभि। अनूषि। अर्कैः। ब्रह्म। च। गिरः। दधिरे। सं। अस्मिन्। महान्। च। स्तोमः।
अधि। वर्धत्। इंद्रे। वर्धात्। यं। यज्ञः। उत। सोमः। इंद्रं। वर्धात्। ब्रह्म। गिरः। उक्था। च। मन्म। वर्ध। अह। ९८

© Dharmartha Trust J&K. Digitized by eGangotri

एनं। उषसः। यामन्। अक्तोः। वर्द्धान्। मासाः। शरदः। द्यावः। इंद्रं॥ एव। जज्ञानं। सहसे। असामि। ववृधानं।
राधसे। च। श्रुताय। महां। उग्रं। अवसे। विप्र। नूनं। आ। विवासेम। वृत्रऽतूर्येषु॥ १०॥ मंद्रस्य। कवेः। दि
व्यस्य। वह्नेः। विप्रऽमन्मनः। वचनस्य। मध्वः। अपाः। नः। तस्य। सचनस्य। देव। इषः। युवस्व। गृणते। गो
ऽअग्राः। अयं। उशानः। परि। अद्रिं। उस्राः। ऋतधीतिऽभिः। ऋतऽयुक्। युजानः। रुजत्। अरुग्णं। वि।
वलस्य। सानुं। पणीन्। वचःऽभिः। अभि। योधत्। इंद्रः॥ अयं। द्योतयत्। अद्युतः। वि। अक्तून्। दोषा। व
स्तोः। शरदः। इंदुः। इंद्र। इमां। केतुं। अदधुः। नु। चित्। अह्नां। शुचिऽजन्मनः। उषसः। चकार॥ अयं। रोचय
त्। अरुचः। रुचानः। अयं। वासयत्। वि। ऋतेन। पूर्वीः॥ अयं। ईयते। ऋतयुक्ऽभिः। अश्वैः। स्वःऽविदा।

© Dharmartha Trust J&K. Digitized by eGangotri

१-च. नाभिना।चर्षणिऽप्राः।गृणानः।गृणते।प्रत्ना।राजन्।इषः।पिन्व।वसुऽदेयाय।पूर्वीः।अपः।ओषधीः।अ
१५ विषा।वनानि।गाः।अर्वतः।नॄन्।ऋचसे।रिरीहि॥३॥इंद्र।पिब।तुभ्यं।सुतः।मदाय।अव।स्य।हरी इति
विमुच।सखाया।उत।प्रऽगाय।गणे।आ।आ।निऽसद्य।अथ।यज्ञाय।गृणते।वयः।धाः।अस्य।पिब।
यस्य।जज्ञानः।इंद्र।मदाय।क्रत्वे।अपिबः।विऽरप्शिन्।तं।ऊं इति।ते।गावः।नरः।आपः।अद्रिः।इंदुं।
सं।अह्यन्।पीतये।सं।अस्मै।संऽइद्धे।अग्नौ।सुते।इंद्र।सोमे।आ।त्वा।वहंतु।हरयः।वहिष्ठाः।
त्वाऽयता।मनसा।जोहवीमि।इंद्र।आ।याहि।सुविताय।महे।नः।आ।याहि।शश्वत्।उशता।
ययाथ।इंद्र।महा।मनसा।सोमऽपेयं।उप।ब्रह्माणि।शृणवः।इमा।नः।अथ।ते।यज्ञः।तन्वे।व १५

© Dharmartha Trust J&K. Digitized by eGangotri

यः। धाता। यन्ता। इंद्र। दिवि। पार्ये। यन्ता। ऋधक्। यन्ता। वा। त्वं। सदनः। यन्त्रा। वा। असि। अनः। नः। यज्ञं।
अव। स्तो। नि। युत्वानः। सः। जोषाः। पाहि। गिर्वणः। मरुत्ऽभिः। १२। अर्हेक मानः। उप। याहि। यज्ञं।
तुभ्यं। पवंते। इंदवः। सुताः। सः। गावः। न। वज्रिन्। स्वं। ओकः। अच्छ। इंद्र। आ। गहि। प्रथमः। यज्ञिया
नां। या। ते। काकुत्। सुऽकृता। या। वरिष्ठा। यया। शश्वत्। पिबसि। मध्वः। ऊर्मिं। तया। पाहि। प्र। ते।
अध्वर्युः। अस्थात्। सं। ते। वज्रः। वर्ततां। इंद्र। गव्युः। एषः। द्रप्सः। वृषभः। विश्वऽरूपः। इंद्राय। वृष्णे।
सं। अकारि। सोमः। एतं। पिब। हरिऽवः। स्थातः। उग्र। यस्य। ईशिषे। प्रऽदिवि। यः। ते। अन्नं। सुतः।
सोमः। असुतः। इंद्र। वस्यान्। अयं। श्रेयान्। चिकितुषे। रणाय। एतं। तितिर्वः। उप। याहि। यज्ञं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ तेन।विश्वाः।नवीषीः।आ।पृण स्व।कृयामसि।त्वा।आ।इंद्र।याहि।अर्वाङ्।अरं।ते।सोमः।तन्वे।भू
९६ वाति।शतक्रतोइति शतऽक्रतो।मादयस्व।सुतेषु।प्र।अस्मान्।अव।पृतनासु।प्र।विक्षु॥३॥प्र
९८ नि।अस्मै।पिपीषते।विश्वानि।विदुषे।भर।अरंऽगमाय।जग्मये।अपश्चात्ऽदघ्वने।नरे॥आ।ई
एनं।प्रति।एतना।सोमेभिः।सोमऽपातमं।अमत्रेभिः।ऋजीषिणं।इंद्रं।सुतेभिः।इंदुऽभिः।यत्।सु
तेभिः।इंदुऽभिः।सोमेभिः।प्रतिऽभूषथ।वेद।विश्वस्य।मेधिरः।धृषत्।तंतं।इत्।आ।ईषते॥अस्मैऽ
अस्मै।इत्।ऊं।अंधसः।अध्वर्यो इति।प्र।भर।सुतं।कुवित्।समस्य।जेन्यस्य।शर्धतः।अभिऽशस्तेः
।अवऽस्परत्॥४॥यस्य।त्यत्।शंबरं।मदे।दिवःऽदासाय।रंधयः।अयं।सः।सोमः।इंद्र।ते।सुतः। ९६

© Dharmartha Trust J&K. Digitized by eGangotri

पिब। यस्य। तीव्रऽसुतं। मदं। मध्यं। अंतं। च। रक्षसे।०। यस्य। गाः। अंतः। अश्मनः। मदे। दृह्ळाः। अवऽअसृ
जः।०। यस्य। मंदानः। अंधसः। माघोनं। दधिषे। शवः।०।१५।। यः। रयिऽवः। रयिंऽतमः। यः। द्युम्नैः। द्यु
म्नवत्ऽतमः। सोमः। सुतः। सः। इंद्र। ते। अस्ति। स्वधाऽपते। मदः। यः। शग्मः। तुविऽशग्म। ते। रायः। दा
मा। मतीनां।०। येन। वृद्धः। न। शवसा। तुरः। न। स्वाभिः। ऊतिऽभिः।०। त्यं। ऊं इति। वः। अप्रऽहनं। गृ
णीषे। शवसः। पतिं। इंद्रं। विश्वऽसहं। नरं। मंहिष्ठं। विश्वऽचर्षणिं। यं। वर्धयंति। इत्। गिरः। पतिं। तुर
स्य। राधसः। तं। इत्। नु। अस्य। रोदसी इति। देवी इति। शुष्मं। सपर्यतः।।१६।। तत्। वः। उक्थस्य। ब
र्हणा। इंद्राय। उपऽस्तृणीषणि।। विपः। न। यस्य। ऊतयः। वि। यत्। रोहंति। सऽक्षितः। अविदत्। द

१.५. क्षां। मित्रः। नवीयान्। पपानः। देवेभ्यः। वस्यः। अचैत्। ससऽवान्। स्तौलाभिः। धौतरीभिः। उरुष्या। पायुः।
८ । अभवत्। सखिऽभ्यः। ऋतस्य। पथिा। वेधाः। अपायि। श्रिये। मनांसि। देवासः। अक्रन्। दधानः। ना
97 मा। महः। वचःऽभिः। वपुः। दृशये। वेन्यः। विः। आ। वरित्यावः। द्युमन्ऽनमं। दक्षं। धेहि। अस्मे इति। सेध।
जनानां। पूर्वीः। अरातीः। वर्षीयः। वयः। कृणुहि। शचीभिः। धनस्य। सातौ। अस्मान्। अविड्ढि। इंद्र।
तुभ्यं। इत्। मघऽवन्। अभूम। वयं। दात्रे। हरिऽवः। मा। वि। वेनः। नकिः। आपिः। ददृशे। मर्त्यऽत्रा। किं।
अंग। रध्रऽचोदनं। त्वा। आहुः। ५। मा। जस्वने। वृषभ। नः। ररीथाः। मा। ते। रेवतः। सख्ये। रिषाम।
पूर्वीः। ते। इंद्र। निःऽसिधः। जनेषु। जहि। असुस्वीन्। प्र। वृह। अपृणतः। उग्र। अभ्राणिऽइव। स्तनयन्। ९

© Dharmartha Trust J&K. Digitized by eGangotri

इयर्ति।इंद्रः।राधांसि।अश्व्यानि।गव्या।त्वं।असि।प्रऽदिवः।कारुऽधायाः।मा।त्वा।अदामानः।आ।द
भन्।मघोनः।अध्वर्यो इति।वीराः।प्र।महे।सुतानां।इंद्राय।भर।सः।हि।अस्य।राजा।यः।पूर्व्याभिः।उत।
नूतनाभिः।गीःऽभिः।ववृधे।गृणतां।ऋषीणां।अस्य।मदे।पुरु।वर्पांसि।विद्वान्।इंद्रः।वृत्राणि।अप्रति
जघान।तं।ऊं इति।प्र।होषि।मधुऽमंतं।अस्मै।सोमं।वीराय।शिप्रिणे।पिबध्यै।०हंता।०।गंता।यज्ञं।प
राऽवतः।चित्।अच्छ।वसुः।धीनां।अविता।कारुऽधायाः।१०।इदं।सत्।पात्रं।इंद्रऽपानं।इंद्रस्य।प्रियं।
अमृतं।अपायि।मत्सत्।यथा।सौमनसाय।देवं।वि।अस्मत्।द्वेषः।युयवत्।वि।अंहः।९।एना।मंदानः।
जहि।शूर।शत्रून्।जामिं।अजामिं।मघऽवन्।अमित्रान्।अभिऽसेनान्।अभि।आऽददिशानान्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ पराचः।इंद्र।प्र।मृण।जहि।च।आ।सु।स्मा।नः।मघऽवन्।इंद्र।पृत्ऽसु।अस्मभ्यं।महि।वरिवः।सुऽगं।

१९ करिति कः।अपां।तोकस्य।तनयस्य।जेषे।इंद्र।सूरीन्।कृणुहि।स्मा।नः।अर्द्धं।आ।त्वा।हरयः।वृषण

98 ः।युजानाः।वृषऽरथासः।वृषऽरश्मयः।अत्याः।अस्मत्राञ्चः।वृषणः।वज्रऽवाहः।वृष्णे।मदाय।सुऽ

युजः।वहंतु।आ।ते।वृषन्।वृषणः।द्रोणं।अस्थुः।घृतऽप्रुषः।न।ऊर्मयः।मदंतः।इंद्र।प्र।तुभ्यं।वृषऽभिः।

सुतानां।वृष्णे।भरंति।वृषभाय।सोमं॥१॥ वृषा।असि।दिवः।वृषभः।पृथिव्याः।वृषा।सिंधूनां।

वृषभः।स्तियानां।वृष्णे।ते।इंदुः।वृषभ।पीपाय।स्वादुः।रसः।मधुऽपेयः।वराय।अयं।देवः।सहसा

जायमानः।इंद्रेण।युजा।पणिं।अस्तभायत्।अयं।स्वस्य।पितुः।आयुधानि।इंदुः।अमुष्णात्। १९

© Dharmartha Trust J&K. Digitized by eGangotri

अशिवस्य। मायया॑ऽ। अयं। अकृणोत्। उषसः। सुऽपत्नीः। अयं। सूर्ये। अदधात्। ज्योतिः। अंतरिति। अ
यं। त्रिऽधातु। दिवि। रोचनेषु। त्रितेषु। विंदत्। अमृतं। निऽगूळ्हं। अयं। द्यावापृथिवी इति। वि। स्कभा
यत्। अयं। रथं। अयुनक्। सप्तऽरश्मिं। अयं। गोषु। शच्या। पक्वं। अंतरिति। सोमः। दाधार। दशऽयंत्रं
। उत्सं॥२०॥ यः। आ। अनयत्। पराऽवतः। सुऽनीती। तुर्वशं। यदुं। इंद्रः। सः। नः। युवा। सखा॥ अविप्रे।
चित्। वयः। दधत्। अनाशुना। चित्। अर्वता। इंद्रः। जेता। हितं। धनं। महीः। अस्य। प्रऽनीतयः। पूर्वीः।
उत। प्रऽशस्तयः। न। अस्य। क्षीयंते। ऊतयः। सखायः। ब्रह्मऽवाहसे। अर्चत। प्र। च। गायत। सः। हि। न
ः। प्रऽमतिः। मही। त्वं। एकस्य। वृत्रऽहन्। अविता। द्वयोः। असि। उत। ईदृशे। यथा। वयं॥२१॥ नयसि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ व॰ इता । ॐ इति । अलि । हिषः । रुणो । षि । उक्थऽशंसिनः । न्दऽभिः । सुऽवीरः । ऋध्यसे । ब्रह्माणं । ब्रह्मऽवाह

९९ सांगीःऽभिः । सखायं । ऋग्मियं । गां । न । दोहसे । हुवे । यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि

दृह्ळा । वीरस्य । पृतनाऽसहः । वि । दृळ्हानि । चित् । अद्रिऽवः । जनानां । शचीऽपते । वृह । मायाः । अना

99 नत । ॐ इति । त्वा । सत्या । सोमऽपाः । इंद्र । वाजानां । पते । अहूमहि । श्रवस्यवः ॥ २२ ॥ ० यः । पुरा । आ

सिथ । यः । वा । नूनं । हिते । धने । हव्यः । सः । श्रुधि । हवं । धीऽभिः । अर्वन्ऽभिः । अर्वतः । वाजान् । इंद्र । श्र

वाय्यान् । त्वया । जेष्म । हिते । धने । अभूः । ॐ इति । वीर । गिर्वणः । महान् । इंद्र । धने । हिते । भरे । वितंतु

साय्यः । ० अमित्रऽहन् । मक्षुऽजवः । तमा । असनि । नय । नः । हिनुहि । रथं । सः । रथेन । रथिऽतमः ॥ ९९

© Dharmartha Trust J&K. Digitized by eGangotri

अस्माकेन। अभिऽयुग्वना। जेषि। जिष्णो इति। हितं। धनं। २३। ७। कृष्टीनां। विऽचर्षणिः। पतिः। ज
ज्ञे। वृषऽक्रतुः। यः। गृणतां। इत्। आसिथ। आपिः। ऊती। शिवः। सखा। सः। त्वं। नः। इंद्र। मृळय। धि
षा। वज्रिं। गभस्त्योः। रक्षःऽहत्याय। वज्रिऽवः। ससहीष्ठाः। अभि। स्पृधः। प्रत्नं। रयीणां। युजं। सखा
यं। कीरिऽचोदनं। ब्रह्मऽवाहःऽतमं। हुवे। सः। हि। विश्वानि। पार्थिवा। एकः। वसूनि। पत्यते। गिर्वणः
ऽतमः। अध्रिऽगुः। २न। सः। नः। नियुत्ऽभिः। आ। पृण। कामं। वाजेभिः। अश्विऽभिः। गोमत्ऽभिः।
गोऽपते। धृषत्। नत। वः। गाय। सुते। सचा। पुरुऽहूताय। सत्वने। शं। यत्। गवे। न। शाकिने। न। घा।
वसुः। नि। यमते। दानं। वाजस्य। गोऽमतः। यत्। सीं। उप। श्रवत्। गिरः। कुवित्ऽसस्य। प्र। हि। व्रजं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.१. गोऽमंतं।दस्युऽहा।गमत्।शचीभिः।अप।नः।वरत्।इमाः।ऊं इति।त्वा।शतक्रतो इति शतऽक्रतो।अ
१० भि।प्र।नोनुवुः।गिरः।इंद्र।वत्सं।न।मातरः।रुपा।दुःऽनशं।सख्यं।तव।गौः।असि।वीर।गव्यते।
अश्वऽवः।अश्वऽयते।भव।सुतेऽसुते।नक्षसे।गिर्वणः।गिरः।वत्सं।गावः।न।धेनवः।पुरुऽतमं।पु
100 रूणां।स्तोतॄणां।विऽवाचि।वाजेभिः।वाजऽयतां।अस्माकं।इंद्र।भूतु।ते।स्तोमः।वाहिष्ठः।अंतमः
।अस्मान्।राये।महे।हिनु।अधि।बृवुः।पणीनां।वर्षिष्ठे।मूर्द्धन्।अस्थात्।उरुः।कक्षः।न।गांग्यः
।यस्य।वायोःऽइव।द्रवत्।भद्रा।रातिः।सहस्रिणी।सद्यः।दाना।य।मंहते।तत्।तु।नः।विश्वे।अर्य
ः।आ।सदा।गृणंति।कारवः।बृबुं।सहस्रऽदातमं।सूरिं।सहस्रऽसातमं।रध्यां।इत्।हि।हवाम १०

© Dharmartha Trust J&K. Digitized by eGangotri

हे। साता। वाजस्य। कारवः। त्वां। वृत्रेषु। इंद्र। सत्ऽपतिं। नरः। त्वां। काष्ठासु। अर्वतः। सः। त्वं। नः। चित्र।
वज्रऽहस्त। धृष्णुऽया। महः। स्तवानः। अद्रिऽवः। गां। अश्वं। रथ्यं। इंद्र। सं। किर। सत्रा। वाजं। न। जिग्यु
षे। यः। सत्राऽहा। विऽचर्षणिः। इंद्रं। तं। हूमहे। वयं। सहस्रऽमुष्क। तुविऽनृम्ण। सत्ऽपते। भव। समत्ऽ
सु। नः। वृधे। बाधसे। जनान्। वृषभाऽइव। मन्युना। घृषौ। मीळ्हे। ऋचीषम। अस्माकं। बोधि। अ
ता। महाऽधने। तनूषु। अप्ऽसु। सूर्ये। इंद्र। ज्येष्ठं। नः। आ। भर। ओजिष्ठं। पपुरि। श्रवः। येन। इमेइति।
चित्र। वज्रऽहस्त। रोदसीइति। आ। उभेइति। सुऽशिप्र। प्राः॥ २७॥ त्वां। उग्रं। अवसे। चर्षणिऽसहं। रा
जन्। देवेषु। हूमहे। विश्वा। सु। नः। विथुरा। पिब्दना। वसोइति। अमित्रान्। सुऽसहान्। कृधि। यत्

© Dharmartha Trust J&K. Digitized by eGangotri

प॰वे॰ इंद्र। नाहुषीषु। आ। ओजः। नृम्णं। च। कृष्टिषु। यत्। वा। पंच। क्षितीनां। द्युम्नं। आ। भर। सत्रा। विश्वा
२१ नि। पौंस्या। यत्। वा। तृक्षौ। मघऽवन्। द्रुह्यौ। आ। जने। यत्। पूरौ। कत्। च। वृष्ण्यं। अस्मभ्यं। तत्।
101 रिरीहि। सं। नृऽसह्ये। अमित्रान्। पृत्ऽसु। तुर्वणे। इंद्र। त्रिऽधातु। शरणं। त्रिऽवरूथं। स्वस्तिऽमत्।
छर्दिः। यच्छ। मघवत्ऽभ्यः। च। मह्यं। च। यवय। दिद्युं। एभ्यः। ये। गव्यता। मनसा। शत्रुं। आऽदभुः। अभिऽप्रघ्नं
ति। धृष्णुऽया। अध। स्म। नः। मघऽवन्। इंद्र। गिर्वणः। तनूऽपाः। अंतमः। भव॥ १०॥ ०। वृधे। भव। इंद्र।
नायं। अव। युधि। यत्। अंतरिक्षे। पतयंति। पर्णिनः। दिद्यवः। तिग्मऽमूर्धानः। यत्र। शूरासः। तन्वः।
विऽतन्वते। प्रिया। शर्म। पितॄणां। अध। स्म। यच्छ। तन्वे। तने। च। छर्दिः। अचित्तं। यवय। द्वेषः। यत्। २१

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्र। सर्गे। अर्वतः। चोदयासे। महःऽधने। असमने। अध्वनि। वृजिने। पथि। श्येनान्ऽइव। श्रवस्यत
ः। सिंधून्ऽइव। प्रवणे। आशुऽया। यतः। यदि। क्रोशं। अनु। स्वनि। आ। ये। वयः। न। वर्वृतति। आमि
षि। गृभीताः। बाह्वोः। गवि। २१। स्वादुः। किल। अयं। मधुऽमान्। उत। अयं। तीव्रः। किल। अयं। रस
वान्। उत। अयं। उतो इति। नु। अस्य। पपिऽवांसं। इंद्रं। न। कः। चन। सहते। आऽहवेषु। अयं। स्वादुः। इ
ह। मदिष्ठः। आस। यस्य। इंद्रः। वृत्रऽहत्ये। ममाद। पुरूणि। यः। च्यौत्ना। शंबरस्य। वि। नवतिं। नव। च
। देह्यः। हन्। अयं। मे। पीतः। उत्। इयर्ति। वाचं। अयं। मनीषां। उशतीं। अजीगरिति। अयं। षट्।
उर्वीः। अमीमित। धीरः। न। याभ्यः। भुवनं। कत्। चन। आरे। अयं। सः। यः। वरिमाणं। पृथिव्याः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰वृ॰ वर्ष्माणं। दिवः। अकृणोत्। अयं। सः। अयं। पीयूषं। तिसृषु। प्रवत्ऽसु। सोमः। दाधार। उरु। अंतरिक्षं।
१॰२ अयं। विदत्। चित्रऽदृशीकं। अर्णः। शुक्रऽसद्मनां। उषसां। अनीके। अयं। महान्। महता। स्कंभनेन। उत्।
102 द्यां। अस्तभ्नात्। वृषभः। मरुत्वान्॥ ३०॥ धृषत्। पिब। कलशे। सोमं। इंद्र। वृत्रऽहा। शूर। संऽअरे।
वसूनां। माध्यंदिने। सवने। आ। वृषस्व। रयिऽस्थानः। रयिं। अस्मासु। धेहि। इंद्र। प्र। नः। पुरएताऽ
इव। पश्य। प्र। नः। नय। प्रऽतरं। वस्यः। अछ। भव। सुऽपारः। अतिऽपारयः। नः। भव। सुऽनीतिः। उत।
वामऽनीतिः। उरुं। नः। लोकं। अनु। नेषि। विद्वान्। स्वःऽवत्। ज्योतिः। अभयं। स्वस्ति। ऋष्वा। ते। इंद्र।
स्थविरस्य। बाहू इति। उप। स्थेयाम। शरणा। बृहंता। वरिष्ठे। नः। इंद्र। वंधुरे। धाः। वहिष्ठयोः। शतऽ १॰२

© Dharmartha Trust J&K. Digitized by eGangotri

वन्। अभ्वयोः। आ। इषं। आ। वक्षि। इषां। वर्षिष्ठां। मा। नः। तारीत्। मघऽवन्। रायः। अर्यः। इंद्र। मृळ। मह्
यं। जीवातुं। इच्छ। चोदय। धियं। अयसः। न। धारां। यत्। किं। च। अहं। त्वाऽयुः। इदं। वदामि। तत्। जुष
स्व। कृधि। मा। देवऽवंतं। ॥३॥ त्रातारं। इंद्रं। अवितारं। इंद्रं। हवेऽहवे। सुऽहवं। शूरं। इंद्रं। ह्वयामि। शक्रं। पु
रुऽहूतं। इंद्रं। स्वस्ति। नः। मघऽवा। धातु। इंद्रः। इंद्रः। सुऽत्रामा। स्वऽवान्। अवःऽभिः। सुऽमृळीकः। भव
तु। विश्वऽवेदाः। बाधतां। द्वेषः। अभयं। कृणोतु। सुऽवीर्यस्य। पतयः। स्याम। ॰। सः। सुऽत्रामा। स्वऽवा
न्। इंद्रः। अस्मे इति। आरात्। चित्। द्वेषः। सनुतः। युयोतु। अव। त्वे इति। इंद्र। प्रऽवतः। न। ऊर्मिः। गिरः।
ब्रह्माणि। निऽयुतः। धवंते। उरु। न। राधः। सवना। पुरूणि। अपः। गाः। वज्रिन्। युवसे। सं। इंदून्। कः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ ई। स्तवता। कः। पृणता। कः। यजाते। यत्। उग्रं। इत्। मघऽवा। विऽश्वहा। अवेत्। पादौ। इव। प्रऽहरन्। अ
१॰३ न्यंऽअन्यं। कृणोति। पूर्वं। अपरं। शचीभिः॥ ३॥ शृण्वे। वीरः। उग्रंऽउग्रं। दमऽयन्। अन्यंऽअन्यं। अ
तिऽनेनीयमानः। एधमानऽद्विट्। उभयस्य। राजा। चोष्कूयते। विशः। इंद्रः। मनुष्यान्। परा। पूर्वेषां। सख्या
वृणक्ति। विऽतर्तुराणः। अपरेभिः। एति। अननुऽभूतीः। अवऽधून्वानः। पूर्वीः। इंद्रः। शरदः। ततर्ति।
रूपंऽरूपं। प्रतिऽरूपः। बभूव। तत्। अस्य। रूपं। प्रतिऽचक्षणाय। इंद्रः। मायाभिः। पुरुऽरूपः। ईयते। युक्
क्ताः। हि। अस्य। हरयः। शता। दश। युजानः। हरिता। रथे। भूरि। त्वष्टा। इह। राजति। कः। विश्वाहा। द्विष
तः। पक्षः। आसते। उत। आसीनेषु। सूरिषु। अगव्यूति। क्षेत्रं। आ। अगन्म। देवाः। उर्वी। सती। भूमिः। १॰३

103

© Dharmartha Trust J&K. Digitized by eGangotri

अंहूरणा। अभूत्। बृहस्पते। प्र। चिकित्स। गोऽइष्टौ। इत्था। सते। जरित्रे। इंद्र। पंथां॥२०॥ दिवेऽदिवे। सऽदृ
शीः। अन्यं। अर्धं। कृष्णाः। असेधन्। अप। सद्मनः। जाः। अहन्। दासा। वृषभः। वस्नऽयंतां। उदऽव्रजे। व
र्चिनं। शंबरं। च। प्रऽस्तोकः। इत्। नु। राधसः। ते। इंद्र। दश। कोशयीः। दश। वाजिनः। अदात्। दिवःऽदासा
त्। अतिथिऽग्वस्य। राधः। शांबरं। वसु। प्रति। अग्रभीष्म। दश। अश्वान्। दश। कोशान्। दश। वस्त्रा।
अधिऽभोजना। दशो इति। हिरण्यऽपिंडान्। दिवःऽदासात्। असानिषं। दश। रथान्। प्रष्टिऽमतः। शतं।
गाः। अथर्वऽभ्यः। अश्वथः। पायवे। अदात्। महि। राधः। विश्वऽजन्यं। दधानान्। भरत्ऽवाजान्। सांर्जयः। ना
अभि। अयष्ट॥२४॥ वनस्पते। वीळुऽअंगः। हि। भूयाः। अस्मत्ऽसखा। प्रऽतरणः। सुऽवीरः। गोभिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰च॰ संऽनद्धः। असि। वीळयस्व। आऽस्थाता। ते। जयतु। जेत्वानि। दिवः। पृथिव्याः। परि। ओजः। उत्ऽभृ

३४ तं। वनस्पतिऽभ्यः। परि। आऽभृतं। सहः। अपां। ओज्मानं। परि। गोभिः। आऽवृतं। इंद्रस्य। वज्रं। ह

विषा। रथं। यज। इंद्रस्य। वज्रः। मरुतां। अनीकं। मित्रस्य। गर्भः। वरुणस्य। नाभिः। सः। इमां। नः।

हव्यऽदातिं। जुषाणः। देव। रथ। प्रति। हव्या। गृभाय। उप। श्वासय। पृथिवीं। उत। द्यां। पुरुऽत्रा। ते। म

नुतां। विऽस्थितं। जगत्। सः। दुंदुभे। सऽजूः। इंद्रेण। देवैः। दूरात्। दवीयः। अप। सेध। शत्रून्। आ। क्रंद

य। बलं। ओजः। नः। आ। धाः। निः। स्तनिहि। दुःऽइता। बाधमानः। अप। प्रोथ। दुंदुभे। दुच्छुनाः। इतः।

इंद्रस्य। मुष्टिः। असि। वीळयस्व। आ। अमूः। अज। प्रतिऽआवर्तय। इमाः। केतुऽमत्। दुंदुभिः। ३४

105

© Dharmartha Trust J&K. Digitized by eGangotri

वावदीति। सं। अश्वऽपर्णाः। चरंति। नः। नरः। अस्माकं। इंद्र। रथिनः। जयंतु॥ ३५॥ इति चतुर्थाष्टके स
प्तमो ध्यायः॥ ॐ नमः॥ ॥ यज्ञायज्ञाद्यधिकारांस्तु स्तृणपाणिकं पृश्निसूक्तं प्रगाथौ बृहतीमहास
तो बृहती महाबार्हत बार्हतौ प्रगाथा विसामेष्वः काकुभः प्रगाथः पुरउष्णिक् बृहत्यतिजग
तिनी मारुत्सौंस्यास्तिस्त्रो वासांलिंगोक्तदेवताः काकुभः प्रगाथः पुरउष्णिक् बृहतीतिपोष्म्यांबृ
हती महाबृहती यवमध्या ऽनुष्टुप् मारुत्स्योस्यां यायामभ्योवांप्रश्ने वर्षीस्तु षेपं चोनः जिश्वा
हवैश्वदेवं हशक्वर्यं तौकृवेवउदुस्यसोवाक्षरा त्रिष्टुप् त्रिगनुष्टुबंतं नतम्यूनासप्तम्याद्याः षड्गायत्र्य
श्चतुर्दशी जगती सुहोत्रादयोनुक्र गोत्राभारद्वाजाः पौत्रा बृहस्पतेर्दौष्यंतेर्वा भरतस्य वसंट

© Dharmartha Trust J&K. Digitized by eGangotri

१.४. शपोरुहं तक्षायत्रं वैयां पूषं ननुष्टुप्सं पूषन्नेहिवां षड्यूऽनमं सानुष्टुबिंद्राग्नेयंदंचं श्रुक्रेचतुष्कं
३.५ द्विती याजगती प्रनुदशैंद्राग्नं तबोंहेतं चतुरनुष्टुबंतं प्रथपंचोनागायत्रंतुत्रित्रिष्टुबादित्रिष्टुब्बृह
त्यनुष्टुबंतं मित्रं पंक्ता सारस्वतं त्रिजगत्यादिजगतीत्रिष्टुबंतं ॥३१॥ ॥ओं नमः॥ यज्ञाऽयज्ञा। वः
105 । अग्नये। गिरःऽगिरा। च। दक्षसे। प्रऽप्र। वयं। अमृतं। जातऽवेदसं। प्रियं। मित्रं। न। शंसिषं॥ ऊर्जः।
नपातं। सः। हि। नः। अयं। अस्मऽयुः। दाशेम। हव्यऽदातये। भुवत्। वाजेषु। अविता। भुवत्। वृधः।
उत। त्राता। तनूनां। व पाहि। अग्ने। अजरः। महान्। विऽभासि। अर्चिषा। अजस्रेण। शोचिषा। शोशु
चतः। शुचे। सुदीतिऽभिः। सु। दीदिहि। महः। देवान्। यजसि। यक्षि। आनुषक्। नवा। क्रत्वा। उत। दंस ३.५

© Dharmartha Trust J&K. Digitized by eGangotri

ना। अर्वाचः। सीं। कृणुहि। अग्ने। अवसे। रास्व। वाजा। उत। वंस्व। यं। आपः। अद्रयः। वना। गर्भं। ऋतस्य
। पिप्रति। सहसा। यः। मथितः। जायते। नृऽभिः। पृथिव्याः। अधि। सानवि॥ ३॥ आ। यः। पप्रौ। भानुना
। रोदसी इति। उभे इति। धूमेन। धावते। दिवि। तिरः। तमः। ददृशे। ऊर्म्यासु। आ। श्यावासु। अरुषः। वृषा
। आ। श्यावाः। अरुषः। वृषा। बृहत्ऽभिः। अग्ने। अर्चिऽभिः। शुक्रेण। देव। शोचिषा। भरत्ऽवाजे। सम्ऽइ
धानः। यविष्ठ्य। रेवत्। नः। शुक्र। दीदिहि। द्युऽमत्। पावक। दीदिहि। विश्वासां। गृहऽपतिः। विशां। असि
। त्वं। अग्ने। मानुषीणां। शतं। पूःऽभिः। यविष्ठ। पाहि। अंहसः। संऽइद्धारं। शतं। हिमाः। स्तोतृऽभ्यः।
ये। च। ददति। त्वं। नः। चित्रः। ऊत्या। वसो इति। राधांसि। चोदय। अस्य। रायः। त्वं। अग्ने। रथीः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. आसि। विदाः। गाधं। नु। चो। नुनः। पर्षि। तो। कं। नन। यं। पर्त्रऽऽत्वं। अदब्धैः। अम्नवृवऽभिः। अग्ने। हेकां। सि
१०६ दिव्या। युयोधि। नः। अदेवानि। ह्रुरांसि। च। रा। आ। सऽखायः। सबःऽदुघां। धेनुं। अजध्वं। उप। नव्य
सा। वचः। सृजध्वं। अनपऽस्फुरां। या। शर्द्धीय। मारुताय। स्वऽभानवे। श्रुवः। अमृत्यु। धुक्षत। या। मृ
ळीके। मरुतां। तुराणां। या। सुम्नैः। एवऽयावरी। भरत्ऽवाजा। या। अवा। धुक्षत। हि। ता। धेनुं। च। विश्वऽ
दोहसा। इषं। च। विश्वऽभोजसं। तां। वः। इन्द्रं। न। सुऽक्रतुं। वरुणंऽइव। मायिनं। अर्यमणं। न। मन्द्रं। सृप्र
ऽभोजसं। विष्णुं। न। स्तुषे। आऽदिशे। त्वेषं। शर्धः। न। मारुतं। तुविऽस्वनि। अनर्वाणं। पूषणं। सं। यथा।
शता। सं। सहस्रा। कारिषत्। चर्षणिऽभ्यः। आ। आविः। गूळ्हा। वसु। करत्। सुऽवेदा। नः। वसु। करत्। १.६

106

© Dharmartha Trust J&K. Digitized by eGangotri

आ।मा।पूषन्।उप।द्रव।शंसिषं।नु।ते।अपिऽकर्णे।आघृणे।अघ।अर्यः।अरातयः।३।आ।मा।का

कंबीरं।उत।रहः।वनस्पतिं।अशस्तीः।वि।हि।नीनशः।मा।उत।सूरः।अहरिति।एव।चन।ग्री

वाः।आऽदधते।वेरिति।वेः।दृतेःऽइव।ते।अवृकं।अस्तु।सख्यं।अछिद्रस्य।दधन्ऽवतः।सुऽपूर्णस्य।

दधन्ऽवतः।परः।हि।मर्त्यैः।असि।समः।देवैः।उत।श्रिया।अभि।ख्यः।पूषन्।पृतनासु।नः।त्वं

।अव।नूनं।यथा।पुरा।वामी।वामस्य।धूतयः।प्रऽनीतिः।अस्तु।सूनृता।देवस्य।वा।मरुतः।म

र्त्यस्य।वा।ईजानस्य।प्रऽयज्यवः।सद्यः।चित्।यस्य।चर्कृतिः।परि।द्यां।देवः।न।एति।सूर्यः।त्वेषं।

शवः।दधिरे।नाम।यज्ञियं।मरुतः।वृत्रऽहं।शवः।ज्येष्ठं।वृत्रऽहं।शवः।सरुता।ह।द्यौः।अजायत।

© Dharmartha Trust J&K. Digitized by eGangotri

प·वं· सऽकृत्व। भूमिऽभिः। अनऽआयत। पथ्याः। दुग्धं। सऽकृत्व। पयः। तत्। अन्यः। न। अनु। आ। यते॥ ४॥ स्तुषे।
१०७ जनं। सुऽव्रतं। नव्यसीभिः। गीःऽभिः। मित्रावरुणा। सुम्नऽयंता। ते। आ। गमंतु। ते। इह। श्रुवंतु। सु
107 ऽक्षत्रासः। वरुणः। मित्रः। अग्निः। विशःऽविशः। ईड्यं। अध्वरेषु। अदृप्तऽक्रतुं। अरतिं। युवत्योः। दि
वः। शिशुं। सहसः। सूनुं। अग्निं। यज्ञस्य। केतुं। अरुषं। यजध्यै। अरुषस्य। दुहितरा। विरूपे इति वि
वि ऽरूपे। स्तृऽभिः। अन्या। पिपिशे। सूरः। अन्या। मिथःऽतुरा। विचरंती इति विऽचरंती। पावके इति। मन्म
श्रुतं। नक्षतः। ऋच्यमाने इति। प्र। वायुं। अच्छ। बृहती। मनीषा। बृहत्ऽरयिं। विश्वऽवारं। रथऽप्रां।
द्युतन्ऽयामा। निऽयुतः। पत्यमानः। कविः। कविं। इयक्षसि। प्रयज्यो इति प्रऽयज्यो। सः। मे। वपुः। छ १०७

© Dharmartha Trust J&K. Digitized by eGangotri

दधन्। अश्विनोः। यः। रथः। विऽरुक्मान्। मनसा। युजानः। ०। ५। पर्जन्यवाता। वृषभा। पृथिव्याः।
पुरीषाणि। जिन्वतं। अप्यानि। सत्यऽश्रुतः। कवयः। यस्य। गीःऽभिः। जगतः। स्थातः। जगत्। आ।
कृणुध्वं। प्रावीरवी। कन्या। चित्रऽआयुः। सरस्वती। वीरऽपत्नी। धियं। धात्। ग्नाभिः। अच्छिद्रं। शु
रणं। सऽजोषाः। दुःऽआधर्षं। गृणता। शर्म। यंसत्। पथःऽपथः। परिऽपतिं। वचस्या। कामेन। कृतः।
अभि। आनट्। अर्कं। सः। नः। रासत्। शुरुधः। चंद्रऽअग्राः। धियंऽधियं। सीसधाति। प्र। पूषा। प्र
म थमः। भाजं। यशसं। वयःऽधां। सुऽपाणिं। देवं। सुऽगभस्तिं। ऋभ्वं। होता। यक्षत्। यजतः। पस्त्यानां।
अग्निः। त्वष्टारं। सुऽहवं। विभाऽवा। भुवनस्य। पितरं। गीःऽभिः। आभिः। रुद्रं। दिवा। वर्धय। रुद्रं।

© Dharmartha Trust J&K. Digitized by eGangotri

प. च. अक्तो । व्युहंतौ । ऋषं । भजंते । सुऽसुम्नं । ऋधक् । कृवेमा । कविना । इषिता । सः । द्या । आ । सुवा । नः । कवयः

१०८ । यज्ञियासः । मरुतः । गंत । गृणतः । वरस्यां । अचित्रं । चित् । हि । जिन्वथ । वृधंतः । इत्था । नक्षंतः । नरः

अंगिरस्वत् । प्र । वीराय । प्र । तवसे । तुराय । अज । यूथाऽइव । पशुऽरक्षिः । अस्तः । सः । पिस्पृशाति । त

108 न्वि । श्रुतस्य । स्तृऽभिः । न । नाकं । वचनस्य । विपः । यः । रजांसि । विऽममे । पार्थिवानि । त्रिः । चित् ।

विष्णुः । मनवे । बाधिताय । नस्यां । ने । शर्मन् । तु । उपऽदद्यमाने । राया । मदेम । तन्वा । तना । च । तना । नः

अहिः । बुध्न्यः । अनुऽभिः । अर्कैः । नत्व । पर्जतः । ननु । सविता । चनः । धात् । नन्त । ओषधीभिः । अभि ।

रातिऽसाचः । भगः । पुरंऽधिः । जिन्वतु । प्र । राये । नु । नः । रथ्यं । रथ्यां । चर्षणिऽप्राः । पुरुऽवीरं । महः । १०८

© Dharmartha Trust J&K. Digitized by eGangotri

ऋतस्य। गोपां। क्षयं। दाता। अजरं। येन। जना। स्पृधः। अदेवीः। अभि। च। क्रमाम। विशः। आऽदेवीः। अ
भि। अश्नवाम। ७। कुवे। वः। देवीं। अदितिं। नमःऽभिः। मृळीकाय। वरुणं। मित्रं। अग्निं। अभिऽक्षदां।
अर्यमणं। सुऽशेवं। त्रातॄन्। देवान्। सवितारं। भगं। च। सुऽज्योतिषः। सूर्यं। दक्षऽपितॄन्। अनागाःऽत्वे।
सुऽमहः। वीहि। देवान्। द्विऽजन्मानः। ये। ऋतऽसापः। सत्याः। स्वःऽवंतः। यजताः। अग्निऽजिह्वाः। उत। द्या
वापृथिवी इति। क्षत्रं। उरु। बृहंता। रोदसी इति। शरणं। सुसुम्ने इति सुऽसुम्ने। महः। करथः। वरिवः। यथा।
नः। अस्मे इति। क्षयाय। धिषणे इति। अनेहः। आ। नः। रुद्रस्य। सूनवः। नमंतां। अद्य। हूतासः। वसवः।
अधृष्टाः। यत्। ईं। अर्भे। महति। वा। हितासः। बाधे। मरुतः। अह्वाम। देवान्। मिम्यक्ष। येषु। रोदसी।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ च॰ नु। देवी। सिसक्ति। पूषा। अभ्यर्धऽयज्वा। भुवत्। हवं। मरुतः। यत्। ह। याथ। भूम। रेजंते। अध्वनि। प्रऽवि

१०९ क्तेषु। आ। अभि। त्यं। वीरं। गिर्वणसं। अर्च। इंद्रं। ब्रह्मणा। जरितः। नवेन। श्रवत्। इत्। हवं। उप। च। स्तवा

109 नः। रासत्। वाजान्। उप। महः। गृणानः। ओमानं। आपः। मानुषीः। अमृक्तं। धात। तोकाय। तनयाय।

शं। योः। यूयं। हि। स्थ। भिषजः। मातृऽतमाः। विश्वस्य। स्थातुः। जगतः। जनित्रीः। आ। नः। देवः। सविता।

त्रायमाणः। हिरण्यऽपाणिः। यजत्रः। जगम्यात्। यः। दत्रऽवान्। उषसः। न। प्रतीकं। विऽऊर्णुते। दाशुषे।

वार्याणि। उत। त्वं। सूनो इति। सहसः। नः। अद्य। आ। देवान्। अस्मिन्। अध्वरे। ववृत्याः। स्यां। अहं। ते।

सदं। इत्। रातौ। तव। स्यां। अग्ने। अवसा। सुऽवीरः। उत। स्या। मे। हवं। आ। जग्म्यातं। नासत्या। धीभिः। १०९

© Dharmartha Trust J&K. Digitized by eGangotri

युवं। अंग। विप्रा। अत्रिं। न। महः। तमसः। अमुमुक्तं। तूर्वतं। नरा। दुःऽइतात्। अभीके॥ ५॥ ते। नः। रायः।
द्युऽमतः। वाजऽवतः। दातारः। भूत। नृऽवतः। पुरुऽक्षोः। दशस्यंतः। दिव्याः। पार्थिवासः। गोऽजाताः। अप्या
ः। मृळत। च। देवाः॥ ते। नः। रुद्रः। सरस्वती। सऽजोषाः। मीळ्हुष्मंतः। विष्णुः। मृळंतु। वायुः। ऋभुक्षाः। वा
जः। दैव्यः। विऽधाता। पर्जन्यावाता। पिप्यतां। इषं। नः। उत। त्यः। देवः। सविता। भगः। नः। अपां। नपात्।
अवतु। दानु। पप्रिः। त्वष्टा। देवेभिः। जनिऽभिः। सऽजोषाः। द्यौः। देवेभिः। पृथिवी। समुद्रैः। उत। नः। अ
हिः। बुध्न्यः। शृणोतु। अजः। एकऽपात्। पृथिवी। समुद्रः। विश्वे। देवाः। ऋतऽवृधः। हुवानाः। स्तुताः। मंत्राः
। कविऽशस्ताः। अवंतु। एव। नपातः। मम। तस्य। धीभिः। भरत्ऽवाजाः। अभि। अर्चंति। अर्कैः। ग्नाः।

© Dharmartha Trust J&K. Digitized by eGangotri

प·वं· ऋतासः। वसवः। अधृष्टाः। विश्वे। स्तुतासः। भूत। यजत्राः॥१०॥ उत्। ऊं इति। स्यत्। चक्षुः। महि। मि
३·३· त्रयोः। आ। एति। प्रियं। वरुणयोः। अदब्धं। ऋतस्य। शुचि। दृशतं। अनीकं। रुक्मः। न। दिवः। उत्ऽइ
ता। वि। अद्यौत्। वेद। यः। त्रीणि। विदथानि। एषां। देवानां। जन्म। सनुतः। आ। च। विप्रः। ऋजु। मर्ते
षु। वृजिना। च। पश्यन्। अभि। चष्टे। सूरः। अर्यः। एवान्। स्तुषे। ऊं इति। वः। महः। ऋतस्य। गोपान्।
अदितिं। मित्रं। वरुणं। सुऽजातान्। अर्यमणं। भगं। अदब्धऽधीतीन्। अच्छ। वोचे। सऽधन्यः। पाव
कान्। रिशादसः। सत्ऽपतीन्। अदब्धान्। महः। राज्ञः। सुऽवसनस्य। दातॄन्। यूनः। सुऽक्षत्रान्। क्ष
यतः। दिवः। नॄन्। आदित्यान्। यामि। अदितिं। दुवःऽयु। द्यौः। पितः। पृथिवि। मातः। अध्रुक्। ३·३·

© Dharmartha Trust J&K. Digitized by eGangotri

अग्ने । भ्रातः । वसवः । मरुत्वा । नः । विश्वे । आदित्याः । अदिते । सऽजोषाः । अस्मभ्यं । शर्म । बहुलं । वि । यं
त ॥ १२ ॥ मा । नः । वृकाय । वृक्ये । समस्मै । अघऽयते । रीरधत । यजत्राः ॥ ० ॥ रथ्यः । नः । तनूनां । यूयं । दक्ष
स्य । वर्चसः । बभूव । मा । वः । एनः । अन्यऽकृतं । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे । विश्वस्य
। हि । क्षयथ । विश्वऽदेवाः । स्वयं । रिपुः । तन्वं । रिरिषीष्ट ॥ नमः । इत् । उग्रं । नमः । आ । विवासे । नमः । दा
धार । पृथिवीं । उत । द्यां । नमः । देवेभ्यः । नमः । ईशे । एषां । कृतं । चित् । एनः । नमसा । आ । विवासे ॥ ऋ
तस्य । वः । रथ्यः । पूतऽदक्षान् । ऋतस्य । पस्त्यऽसदः । अदब्धान् । तान् । आ । नमःऽभिः । उरुऽचक्ष
सः । नॄन् । विश्वान् । वः । आ । नमे । महः । यजत्राः ॥ ते । हि । श्रेष्ठऽवर्चसः । ते । ऊं इति । नः । तिरः । विश्वा

© Dharmartha Trust J&K. Digitized by eGangotri

।प।च। नि। दुःऽइता। नयंति। सुऽक्षत्रासः। वरुणः। मित्रः। अग्निः। ऋतऽधीतयः। वक्मराजऽसत्याः।१२। ते। नः।
३३५ ।इंद्रः। पृथिवी। क्षाम। वर्धन्। पूषा। भगः। अदितिः। पंच। जनाः। सुऽशर्माणः। सुऽअवसः। सुऽनीथाः।
।भवंतु। नः। सुऽत्रात्रासः। सुऽगोपाः।१३। नु। सद्मानं। दिव्यं। नंशि। देवाः। भारद्वाजः। सुऽमतिं। याति। हो २
ता। आसानेभिः। यजमानः। मियेधैः। देवानां। जन्म। वसुऽयुः। ववंद।१४। अप। त्यं। वृजिनं। रिपुं। स्ते
नं। अग्ने। दुःऽआध्यं। दविष्ठं। अस्मत्। सत्ऽपते। कृधि। सुऽगं।१५। ग्रावाणः। सोम। नः। हि। कं। सखिऽत्व
नाय। वावशुः। जहि। नि। अत्रिणं। पणिं। वृकः। हि। सः।०। इंद्रऽज्येष्ठाः। अभिऽद्यवः। कर्त। नः। अध्व
न्। आ। सुऽगं। गोपाः। अमा। अपि। पंथां। अगन्म। हि। स्वस्तिऽगां। अनेहसं। येन। विश्वाः। परि। ३३३

© Dharmartha Trust J&K. Digitized by eGangotri

द्विषः। वृणक्ति। विंदते। वसु॥१६॥ न। तत्। दिवा। न। पृथिव्या। अनु। मन्ये। न। यज्ञेन। न। उत। शमीभि
ः। आभिः। उब्जंतु। तं। सुऽभ्वः। पर्वतासः। नि। हीयतां। अतिऽयाजस्य। यष्टा। अति। वा। यः। मरु
तः। मन्यते। नः। ब्रह्म। वा। यः। क्रियमाणं। निनित्सात्। तपूंषि। तस्मै। वृजिनानि। संतु। ब्रह्मऽद्वि
षं। अभि। तं। शोचतु। द्यौः। किं। अंग। त्वा। ब्रह्मणः। सोम। गोपां। किं। अंग। त्वा। आहुः। अभिश
स्तिऽपां। नः। किं। अंग। नः। पश्यसि। निद्यमानान्। ब्रह्मऽद्विषे। तपुषिं। हेतिं। अस्य। अवंतु। मां।
उषसः। जायमानाः। अवंतु। मा। सिंधवः। पिन्वमानाः। अवंतु। मा। पर्वतासः। ध्रुवासः। अवं
तु। मा। पितरः। देवऽहूतौ। विश्वऽदानीं। सुऽमनसः। स्याम। पश्येम। नु। सूर्यं। उत्ऽचरंतं। तथा।

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. कर्त्ता। वसुऽपतिः। वसूनां। देवान्। ओहानः। अवसा। आऽगमिष्ठः॥१४॥ इंद्रः। नेदिष्ठं। अवसा। आऽ

११२ गमिष्ठः। सरस्वती। सिंधुऽभिः। पिन्वमाना। पर्जन्यः। नः। ओषधीभिः। मयःऽभुः। अग्निः। सुऽशं

सः। सुऽहवः। पिताऽइव। यः। वः। देवाः। घृतऽस्नुना। हव्येन। प्रतिऽभूषति। तं। विश्वे। उप। गच्छथ। उ

प। नः। सूनवः। गिरः। शृण्वंतु। अमृतस्य। ये। सुऽमृळीकाः। भवंतु। नः। विश्वे। देवाः। ऋतऽवृधः।

ऋतुऽभिः। हवनऽश्रुतः। जुषंतां। युज्यं। पयः॥१५॥ स्तोत्रं। इंद्रः। मरुत्ऽगणः। त्वष्टृऽमान्। मित्रः। अ

र्यमा। इमा। हव्या। जुषंत। नः। इमं। नः। अग्ने। अध्वरं। होतः। वयुनऽशः। यज। चिकित्वान्। दैव्यं। ज

नं। विश्वे। देवाः। शृणुत। इमं। हवं। मे। ये। अंतरिक्षे। ये। उप। द्यवि। स्थ। ये। अग्निऽजिह्वाः। उत। वा। ११२

112

© Dharmartha Trust J&K. Digitized by eGangotri

यजत्राः। आ। सद्य। अस्मिन्। बर्हिषि। मादयध्वं। विश्वे। देवाः। मम। शृण्वंतु। यज्ञियाः। उभेइति।
रोदसीइति। अपां। नपात्। च। मन्म। मा। वः। वचांसि। परिऽचक्ष्याणि। वोचं। सुम्नेषु। इत्। वः। अं
तमाः। मदेम। ये। के। च। ज्मा। महिनः। अहिऽमायाः। दिवः। जज्ञिरे। अपां। सधऽस्थे। ते। अस्म
भ्यं। इषये। विश्वं। आयुः। क्षपः। उस्राः। वरिस्यंतु। देवाः। अग्नीपर्जन्यौ। अवतं। धियं। मे। अस्मि
न्। हवे। सुऽहवा। सुऽस्तुतिं। नः। इळां। अन्यः। जनयत्। गर्भं। अन्यः। प्रजाऽवतीः। इषं। आ। धत्तं
। अस्मेइति। ०सुऽउक्तेन। महा। नमसा। आ। विवासे। अस्मिन्। नः। अद्य। विदथे। यजत्राः। वि
श्वे। देवाः। हविषि। मादयध्वं॥ १६॥ वयं। ऊंइति। त्वा। पथः। पते। रथं। न। वाजऽसातये। धिये।

© Dharmartha Trust J&K. Digitized by eGangotri

113

पूषन्।अयुज्महि।अभि।नः।नर्यं।वसु।वीरं।प्रयतऽदक्षिणं।वामं।गृहऽपतिं।नय।अदित्सं
नं।चित्।आघृणे।पूषन्।दानाय।चोदय।पणेः।चित्।वि।म्रद।मनः।वि।पथः।वाजऽसातये
चिनुहि।वि।मृधः।जहि।साधन्तां।उग्र।नः।धियः।परि।तृंधि।पणीनां।आरया।हृदया।क
वे।अथ।ईं।अस्मभ्यं।रंधय।।३।।वि।पूषन्।आरया।तुद।पणेः।इच्छ।हृदि।प्रियं।।आ।
रिख।किकिरा।कृणु।पणीनां।हृदया।कवे।।यां।पूषन्।ब्रह्मऽचोदनीं।आरां।बिभर्षि।
आघृणे।तया।समस्य।हृदयं।।या।ते।अष्ट्रा।गोऽओपशा।आघृणे।पशुऽसाधनी।त
स्याः।ते।सुम्नं।ईमहे।उत।नः।गोऽसनिं।धियं।अश्वऽसां।वाजऽसां।उत।नृऽवत्।कृणुहि। ११३

© Dharmartha Trust J&K. Digitized by eGangotri

वीतये॥३०॥ सं। पूषन्। विदुषा। नय। यः। अंजसा। अनुऽशासति। यः। एव। इदं। इति। ब्रवत्। सं। ऊं इ
ति। पूष्णा। गमेमहि। यः। गृहान्। अभिऽशासति। इमे। एव। इति। च। ब्रवत्। पूष्णः। चक्रं। न। रिष्यति।
न। कोशः। अव। पद्यते। नो इति। अस्य। व्यथते। पविः। यः। अस्मै। हविषा। अविधत्। न। तं। पूषा। अ
पि। मृष्यते। प्रथमः। विंदते। वसु। पूषा। गाः। अनु। एतु। नः। पूषा। रक्षतु। अर्वतः। पूषा। वाजं। सनो
तु। नः॥१०॥ पूषन्। अनु। प्र। गाः। इहि। यजमानस्य। सुन्वतः। अस्माकं। स्तुवतां। उत। माकिः। ने
शत्। मा। कीं। रिषत्। मा। कीं। सं। शारि। केवटे। अथ। अरिष्टाभिः। आ। गहि। शृण्वंतं। पूषणं।
वयं। इर्यं। अनष्टऽवेदसं। ईशानं। रायः। ईमहे। पूषन्। तव। व्रते। वयं। न। रिष्येम। कदा। चन। स्तो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰षं॰ नारः। नः। इह। स्मसि। परि। पूषा। परस्तात्। हस्तं। दधातु। दक्षिणं। पुनः। नः। नष्टं। आ। अजतु॥१०

१३४ ॥आ। इहि। वां। विऽमुचः। नपात्। आघृणे। सं। सचावहै। रथीः। ऋतस्य। नः। भव। रथिःऽतमं। कपर्दि

नं। ईशानं। राधसः। महः। रायः। सखायं। ईमहे। रायः। धारा। असि। आघृणे। वसोः। राशिः। अ

जऽअश्व। धीवतःऽधीवतः। सखा। पूषणं। नु। अजऽअश्वं। उप। स्तोषाम। वाजिनं। स्वसुः। यः। जा

रः। उच्यते। मातुः। दिधिषुं। अब्रवं। स्वसुः। जारः। शृणोतु। नः। भ्राता। इंद्रस्य। सखा। मम। आ। अ

जासः। पूषणं। रथे। निःऽशृंभाः। तेजनऽश्रियं। देवं। वहंतु। बिभ्रतः॥२३॥ यः। एनं। आऽदिदेशति

।करंभऽअत्। इति। पूषणं। न। तेन। देवः। आऽदिशे॥ उत। घा। सः। रथिःऽतमः। सख्या। सत्ऽपतिः। २३४

© Dharmartha Trust J&K. Digitized by eGangotri

युजा। इंद्रः। वृत्राणि। जिघ्नते। उत। अदः। परुषे। गवि। सूरः। चक्रं। हिरण्ययं। नि। ऐरयत्। रथिऽतमः॥
यत्। अद्य। त्वा। पुरुऽस्तुत। ब्रवाम। दस्र। मंतुऽमः। तत्। सु। नः। मन्म। साधय। इमं। च। नः। गोऽएष
णं। सातये। सीसधः। गणं। आरात्। पूषन्। असि। श्रुतः। आ। ते। स्वस्तिं। ईमहे। आरेऽअघां। उ
पऽवसुं। अद्य। च। सर्वऽतातये। श्वः। च। सर्वऽतातये॥ २२॥ इंद्रा। नु। पूषणा। वयं। सख्याय। स्व
स्तये। हुवेम। वाजऽसातये। सोमं। अन्यः। उप। असदत्। पातवे। चम्वोः। सुतं। करंभं। अन्यः।
इछति। अजाः। अन्यस्य। वह्नयः। हरी इति। अन्यस्य। संऽभृता। ताभ्यां। वृत्राणि। जिघ्नते। य
त्। इंद्रः। अनयत्। रितः। महीः। अपः। वृषन्ऽतमः। तत्र। पूषा। अभवत्। सचा। तां। पूष्णः। सुऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ वं॰ मतिं। वयं। वृक्षस्य। प्र। वयांऽइव। इंद्रस्य। च। आ। रभामहे। उत्। पूषणं। युवामहे। अभीशूंनऽ
११५ इव। सारथिः। मह्यै। इंद्रं। स्वस्तये॥ ३॥ शुक्रं। ते। अन्यत्। यजतं। ते। अन्यत्। विषुरूपे इति
विषुऽरूपे। अहनी इति। द्यौःऽइव। असि। विश्वाः। हि। मायाः। अवसि। स्वधाऽवः। भद्रा। ते। पू
षन्। इह। रातिः। अस्तु। अजऽअश्वः। पशुऽपाः। वाजऽपस्त्यः। धियंऽजिन्वः। भुवने। विश्वे। अ
र्पितः। अष्ट्रां। पूषा। शिथिरां। उत्ऽवरीवृजत्। संऽचक्षाणः। भुवना। देवः। ईयते। याः। ते। पूष
न्। नावः। अंतरिति। समुद्रे। हिरण्ययीः। अंतरिक्षे। चरंति। ताभिः। यासि। दूत्यां। सूर्यस्य।
कामेन। कृत। श्रवः। इच्छमानः। पूषा। सुऽबंधुः। दिवः। आ। पृथिव्याः। इळः। पतिः। मघऽवा। दस्म ११५

© Dharmartha Trust J&K. Digitized by eGangotri

ऽवंचं॥ यं। देवासः। अददुः। सूर्यायै। कामेन। कृतं। तवसं। सुऽअंचं॥ रथं॥ प्र। नु। वोच। सुतेषु। वां।
। वीर्या। यानि। चक्रथुः। हतासः। वां। पितरः। देवऽशत्रवः। इंद्राग्नी इति। जीवथः। युवं। बट्। इत्था
। महिमा। वां। इंद्राग्नी इति। पनिष्ठः। आ। समानः। वां। जनिता। भ्रातरा। युवं। यमौ। इहेहऽमात
रा। ओकिवांसा। सुते। सचा। अश्वा। सप्ती इवेति सप्तीऽइव। आदने। इंद्रा। नु। अग्नी इति। अ
वसा। इह। वज्रिणा। वयं। देवा। हवामहे। यः। इंद्राग्नी इति। सुतेषु। वां। स्तवत्। तेषु। ऋतऽवृधा।
जोषऽवाके। वदतः। पज्रऽहोषिणा। न। देवा। भसथः। चन। इंद्राग्नी इति। कः। अस्य। वां। देवौ।
मर्तः। चिकेतति। विषूचः। अश्वान्। युयुजानः। ईयते। एकः। समाने। आ। रथे॥ २५॥ इंद्राग्नी

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. इति। अपात्। इयं। पूर्वा। आ। अगात्। पत्ऽवतीभ्यः। हित्वी। शिरः। जिह्वया। वावदत्। चरत्। त्रिं

११६ शत्। पदा। नि। अक्रमीत्। इंद्राग्नी इति। आ। हि। तन्वते। नरः। धन्वानि। बाह्वोः। मा। नः। अस्मि

116 न्। महाऽधने। परा। वर्क्तं। गोऽइष्टिषु। इंद्राग्नी इति। तपंति। मा। अघाः। अर्यः। अरातयः। अप।

द्वेषांसि। आ। कृतं। युयुतं। सूर्यात्। अधि। इंद्राग्नी इति। युवोः। अपि। वसु। दिव्यानि। पार्थिवा।

आ। नः। इह। प्र। यच्छतं। रयिं। विश्वायुःऽपोषसं। इंद्राग्नी इति। उक्थऽवाहसा। स्तोमेभिः। हवन

ऽश्रुता। विश्वाभिः। गीःऽभिः। आ। गतं। ०। २। श्नथत्। वृत्रं। उत। सनोति। वाजं। इंद्रा। यः। अ

ग्नी इति। सहुरी इति। सपर्यात्। इरज्यंता। वसव्यस्य। भूरेः। सहःऽतमा। सहसा। वाजऽयंता। ११६

© Dharmartha Trust J&K. Digitized by eGangotri

ता। योधिष्टं। अभि। गाः। इंद्र। नूनं। अपः। स्वः। उषसः। अग्ने। ऊळ्हाः। दिशः। स्वः। उषसः। इंद्र। चि
त्राः। अपः। गाः। अग्ने। युवसे। नियुत्वान्। आ। वृत्रऽहना। वृत्रहऽभिः। शुष्मैः। इंद्र। यातं। नमःऽभि
ः। अग्ने। अर्वाक्। युवं। राधःऽभिः। अकवेभिः। इंद्र। अग्ने। अस्मे इति। भवतं। उत्ऽतमेभिः। ता।
हुवे। ययोः। इदं। पप्ने। विश्वं। पुरा। कृतं। इंद्राग्नी इति। न। मर्धतः। उग्रा। विऽघनिना। मृधः। [illegible]
[illegible]ः। इंद्राग्नी इति। हवामहे।०।।२७।। हतः। वृत्राणि। आर्या। हतः। दासानि। सत्पती इति सत्ऽप
ती। हतः। विश्वाः। अप। द्विषः। इंद्राग्नी इति। युवां। इमे। अभि। स्तोमाः। अनूषत। पिबतं। शंऽभु
वा। सुतं।०। इंद्राग्नी इति। ताभिः। आ। गतं। ताभिः। आ। गच्छतं। नरा।०। इंद्राग्नी इति। सोमः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰व॰ पीतये। तां। इंद्रिष्ठा। यः। अर्चिषा। वना। विश्वा। परिऽस्वजन्। कृष्णा। कृणोति। जिह्वया॥ रणा। यः।
११७ दुहा। आ। विवासति। सुम्नं। इंद्रस्य। मर्त्यः। द्युम्नाय। सुऽतराः। अपः। ता। नः। वाजऽवतीः। इषः। आ
117 भूत्। पिपृतं। अर्वतः। इंद्रं। अग्निं। च। वोळ्हवे। उभा। वां। इंद्राग्नी इति। आऽहुवध्यै। उभा। राधसः।
ह सह। मादयध्यै। उभा। दातारौ। इषां। रयीणां। उभा। वाजस्य। सातये। हुवे। वां। आ। नः। गव्ये
भिः। अश्व्यैः। वसव्यैः। उप। गच्छतं। सखा। यो। देवौ। सख्याय। शंऽभुवा। इंद्राग्नी इति। ता। हुवा
महे। इंद्राग्नी इति। शृणुतं। हवं। यजमानस्य। सुन्वतः। वीतं। हव्यानि। आ। गतं। पिबतं। सोम्यं
मधु॥ २३॥ इयं। अददात्। रभसं। ऋणऽच्युतं। दिवःऽदासं। वध्रिऽअश्वाय। दाशुषे। या। श ११७

© Dharmartha Trust J&K. Digitized by eGangotri

श्वंतं। आऽचखादं। अव। सां। पणिं। ता। ते। दात्राणि। तविषा। सरस्वति॥ इयं। शुष्मेभिः। बिसखाः
ऽइव। अरुजत्। सानु। गिरीणां। तविषेभिः। ऊर्मिऽभिः। पारावतऽघ्नीं। अवसे। सुवृक्तिऽभिः।
सरस्वतीं। आ। विवासेम। धीतिऽभिः॥ सरस्वति। देवऽनिदः। नि। बर्हय। प्रऽजां। विश्वस्य।
बृसयस्य। मायिनः। उत। क्षितिऽभ्यः। अवनीः। अविंदः। विषं। एभ्यः। अस्रवः। वाजि नीऽवति।
नी प्र। नः। देवी। सरस्वती। वाजेभिः। वाजिऽवती। धीनां। अवित्री। अवतु॥ यः। त्वा। देवि। सरस्व
ति। उपऽब्रूते। धने। हिते। इंद्रं। न। वृत्रऽतूर्ये॥ त्वं। देवि। सरस्वति। अव। वाजेषु। वाजिनि।
रद। पूषाऽइव। नः। सनिं॥ उत। स्या। नः। सरस्वती। घोरा। हिरण्यऽवर्तनिः। वृत्रऽघ्नी। वष्टि। सु

© Dharmartha Trust J&K. Digitized by eGangotri

ऽस्तुनि। यस्याः। अनंतः। अह्रुतः। त्वेषः। चरिष्णुः। अर्णवः। अमः। चरति। रोरुवत्। सा। नः। विश्वाः

ः। अति। द्विषः। स्वसॄः। अन्याः। ऋतऽवरी। अतन्। अहाऽइव। सूर्यः। उत। नः। प्रिया। प्रियासु। स

प्तऽस्वसा। सुऽजुष्टा। सरस्वती। स्तोम्या। भूत्। ॥२॥ आऽपप्रुषी। पार्थिवानि। उरु। रजः। अंतरि

क्षं। सरस्वती। निदः। पातु। त्रिऽसधस्था। सप्तऽधातुः। पंच। जाता। वर्धयंती। वाजेऽवाजे। ह

व्या। भूत्। प्र। या। महिम्ना। महिना। आसु। चेकिते। द्युम्नेभिः। अन्याः। अपसां। अपःऽतमा

। रथःऽइव। बृहती। विऽभ्वने। कृता। उपऽस्तुत्या। चिकितुषा। सरस्वती। सरस्वति। अभि। नः।

नेषि। वस्यः। मा। अप। स्फरीः। पयसा। मा। नः। आ। धक्। जुषस्व। नः। सख्या। वेश्या। च। ११८

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. मात्स्वत्राक्षेत्राणि। अरण्यानि। गन्मा ॥ ३९ ॥ इति चतुर्थाष्टके अष्टमोध्यायः ॥ ८ ॥ ॥ ८ ॥

११९ संवत् ॥ १८८८ ॥ शाके ॥ १७ ॥ ५३ ॥ खरनामसंवत्सरे दक्षिणायने वर्षर्तौ आश्विने मासे शुक्ल

119 पक्षे प्रतिपत्तिथौ गुरुवासरे तद्दिने इदं पुस्तकं रामचंद्रात्मजपुरुषोत्तमेन लिखितं गुर्जरा ॥ ८ ॥

११९

© Dharmartha Trust J&K. Digitized by eGangotri

चतुर्थीपत्रे ११८ ४

२२७०

© Dharmartha Trust J&K. Digitized by eGangotri

५

प

१६००

© Dharmartha Trust J&K. Digitized by eGangotri

१ श्रीगणेशाय नमः ॥ श्रीशारदां वंदे ॥ हरिः ॐ स्तुप एकादशाश्विनं तुक्तस्यैकपदां तंत्रैष्टुभं माद्या
विराड्ढुडुश्रियेषड्ढुषस्यं त्वैषास्याव पुनर्न्वैकादशा मारुतं विश्वेषां मैत्रावरुणं श्रुष्टीवां मैंद्रा
वरुणमुपां त्वैजगत्यौ सवामष्टावैंद्रावैष्णावं घृतवती षड् द्यावापृथिवीयं जागतमुदुष्य:
सावित्रं त्रित्रिष्टुबंतमिंद्रासोमा पंचैंद्रासोमं यो अद्भिर्भिन्नृचं बार्हस्पत्यं सोमारुद्रा चतुष्कं सो
मारौद्रं जीमूतस्यैवैकोना पायुर्भारद्वाजः संग्रामांगान्स्तवकश्रोभितुष्टाव वर्म धनुर्ज्यामा
र्त्नीषुधिं जगत्यर्धे सारथिमर्धे रश्मीनश्वान्रथं रथगोपां जगत्यायाल्लिंगोक्तदेवताद्वा
भ्यामिषूः प्रतोदं हस्तघ्नं द्वाभ्यामिषूः पराः पंक्त्यादयो लिंगोक्तदेवताः संग्रामाशिषां १

© Dharmartha Trust J&K. Digitized by eGangotri

त्यानुष्टुब्वृजीतआत्माक्केतिचद्वेद्वयोद्ध्याः संभूतोवसतीवरीषुगृह्यमाणासुपुष्करेस्थितवान्सर्वतःपु
ष्करंतत्रविश्वेदेवाआधारयन्नुत्थाययततोमहत्तपश्चकारादृष्टमिंद्रमन्येर्ऋषिभिर्योदृष्टवांस्त
पसापूर्वंस्तोमभागान्परितुष्टःशाक्तब्रूतेयस्यसगुणतोनामजज्ञेवसतःश्रैष्ठ्यकर्मणःस
सप्तमंमंडलंवसिष्ठोपश्यदग्निंपंचाधिकाविराजोष्टादशाद्याः॥ हरिः ऽ ओं स्तुषे। नरा। दि
वः। अस्य। प्रऽसंता। अश्विना। हुवे। जरमाणः। अर्कैः। या। सद्यः। उस्रा। विऽउषि। ज्मः। अंतान्
। युयूषतः। परि। उरू। वरांसि। ता। यज्ञं। आ। शुचिऽभिः। चक्रमाणा। रथस्य। भानुं। रुरुचुः
रजःऽभिः। पुरु। वरांसि। अमिता। मिमाना। अपः। धन्वानि। अति। याथः। अज्रान्। ता। ह

© Dharmartha Trust J&K. Digitized by eGangotri

पं०पं०
२

त्यत्। वर्तिः। यत्। अर्भं। उग्रा। इत्था। धियं। ऊहथुः। शश्वत्। अश्वैः। मनःऽजवेभिः। इषिरैः।
शयध्यै। परि। व्यथिः। दाशुषः। मर्त्यस्य। ता। नव्यसः। जरमाणस्य। मन्म। उप। भूषतः। युयुजा
नसप्ती इति युयुजानऽसप्ती। शुभं। पृक्षं। इषं। ऊर्जं। वहंता। होता। यक्षत्। प्रत्नः। अध्रुक्। युवा
ना। ता। वल्गू इति। दस्रा। पुरुशाकऽतमा। प्रत्ना। नव्यसा। वचसा। आ। विवासे। या। शंसते। स्तु
वते। शंऽभविष्ठा। बभूवतुः। गृणते। चित्रराती इति चित्रऽराती॥ प० ८ ७।३॥ ता। भुज्युं। विऽभिः
। अप्ऽभ्यः। समुद्रात्। तुग्रस्य। सूनुं। ऊहथुः। रजःऽभिः। अरेणुऽभिः। योजनेभिः। भुजंता।
पतत्रिऽभिः। अर्णसः। निः। उपऽस्थात्। वि। जयुषा। रथ्या। यातं। अद्रिं। श्रुतं। हवं। वृषणा

त्रिव
२

© Dharmartha Trust J&K. Digitized by eGangotri

वध्रिऽमत्याः। दस्रास्यंता। न्नायवे। पिप्युथुः। गां। इति। च्यवाना। सुऽमतिं। भुरण्युः इति। यत्। रोद

सीइति। प्रऽदिवः। अस्ति। मृम। हेळः। देवानां। उत। मर्त्यऽत्रा। तत्। आदित्याः। वसवः। रुद्रि

यासः। रक्षःऽयुजे। तपुः। अघं। दधात। यः। ईं। राजानौ। ऋतुऽथा। विऽदधत्। रजसः। मित्रः

। वरुणः। चिकेतत्। गंभीराय। रक्षसे। हेतिं। अस्य। द्रोघाय। चित्। वचसे। आनवाय। अंत

रैः। चक्रैः। तनयाय। वर्तिः। द्युऽमता। आ। यातं। नृऽवता। रथेन। सनुत्येन। त्यजसा। म

र्त्यस्य। वनुष्यतां। अपि। शीर्षा। ववृक्तं। आ। परमाभिः। उत। मध्यमाभिः। नियुत्ऽ

भिः। यातं। अवमाभिः। अर्वाक्। दृळ्हस्य। चित्। गोऽमतः। वि। व्रजस्य। दुरः। वर्तं। गृण

© Dharmartha Trust J&K. Digitized by eGangotri

पं०पं०
२

ते। चित्रराती इति चित्रऽराती॥ प० १००॥२॥ कां त्या। वल्गू इति। पुरुऽहूता। अस्य। दूतः। न। स्तोमः। अविदत्। नमस्वान्। आ। यः। अर्वाक्। नासत्या। ववर्त। प्रेष्ठा। हि। असथः। अस्य। मन्मन्। अरं। मे। गंतं। हवनाय। अस्मै। गृणाना। यथा। पिबाथः। अंधः। परि। ह। त्यत्। वर्तिः। याथः। रिषः। न। यत्। परः। न। अंतरः। तुतुर्यात्। अकारि। वां। अंधसः। वरीमन्। अस्तारि। बर्हिः। सुप्रऽअयनतमं। उत्तानऽहस्तः। युवऽयुः। ववंद। आ। वां। नक्षंतः। अद्रयः। आंजन्। ऊर्ध्वः। वां। अग्निः। अध्वरेषु। अस्थात्। प्र। रातिः। एति। जूर्णिनी। घृताची। प्र। होता। गूर्तऽमनाः। उराणः। अयुक्त। यः। नासत्या। हवीमन्। अधि। श्रिये। दुहिता। सूर्यस्य। रथं। तस्थौ। पुरुऽभुजा। शतऽऊतिं। प्र। मायाभिः। मा

३

यिना। भूतं। अत्र। नरा। नृनू इति। जनिमन्। यज्ञियानां॥ प०८९॥३॥ युवं। श्रीभिः। दर्शताभिः।
आभिः। शुभे। पुष्टिं। ऊहथुः। सूर्यायाः। प्र। वां। वयः। वपुषे। अनु। पप्तन्। नक्षत्। वाणी। सुऽ
स्तुता। धिष्ण्या। वां। आ। वां। वयः। अश्वासः। वहिष्ठाः। अभि। प्रयः। नासत्या। वहंतु। प्र। वां।
रथः। मनःऽजवाः। असर्जि। इषः। पृक्षः। इषिधः। अनु। पूर्वीः। पुरु। हि। वां। पुरुऽभुजा।
देष्णं। धेनुं। नः। इषं। पिन्वतं। असक्रां। स्तुतः। च। वां। माध्वी इति। सुऽस्तुतिः। च। रसाः। च।
येवां। अनु। रातिं। अग्मन्। उत। मे। ऋज्रे इति। पुरयस्य। रघ्वी इति। सुऽमी ब्हे। शतं। पेरुके।
च। पक्वा। शंऽडः। दात्। हिरणिनः। स्मत्ऽदिष्टीन्। दश। वशासः। अभिऽसाचः। ऋष्वान्।

© Dharmartha Trust J&K. Digitized by eGangotri

पं॰पं
४

भरत॒ऽवाजय।वीर॒।नु।गिरे।दात्र॥

सं।वां।शता।नासत्या।सहस्रा।अश्वानां।पुरुऽपंथाः।गिरे।दात्।हता।रक्षांसि।पुरुऽदं

ससा।स्युरितिस्युः।आ।वां।सुम्ने।वरिमन्।सूरिऽभिः।स्यां।प॰ १०३॥ ७॥ उत।ऊं इति।श्रि इत्येकपदा

ये।उषसः।रोचमानाः।अस्थुः।अपां।न।ऊर्मयः।रुशंतः।कृणोति।विश्वा।सुऽपथा।सु

गानि।अभूत्।ऊं इति।वस्वी।दक्षिणा।मघोनी।भद्रा।ददृक्षे।उर्विया।वि।भासि।उत्

ते।शोचिः।भानवः।द्यां।अपप्तन्।आविः।वक्षः।कृणुषे।शुंभमाना।उषः।देवि।रोचमा

ना।महःऽभिः।वहंति।सीं।अरुणासः।रुशंतः।गावः।सुऽभगां।उर्विया।प्रथानां।अप। त्रिव

ईजते।शूरः।अस्ताऽइव।शत्रून्।बाधते।तमः।अजिरः।न।वोळ्हा।सुऽगा।उत।ते। ४

© Dharmartha Trust J&K. Digitized by eGangotri

सुऽपथा। पर्वतेषु। अवाते। अपः। तरसि। स्वभानो इति स्वऽभानो। सा। नः। आ। वह। पृथुऽ
यामन्। ऋष्वे। रयिं। दिवः। दुहितः। इषयध्यै। सा। आ। वह। या। उक्षऽभिः। अवाता। उषः। वरं।
वहसि। जोषं। अनु। त्वं। दिवः। दुहितः। या। ह। देवी। पूर्वऽहूतौ। मंहना। दर्शता। भूः॥ ष॥ प० ९॥
एषा। स्या। नः। दुहिता। दिवःऽजाः। क्षितीः। उच्छंती। मानुषीः। अजीगरिति। या। भानुना।
रुशता। राम्यासु। अज्ञायि। तिरः। तमसः। चित्। अक्तून्। वि। तत्। ययुः। अरुणयुक्ऽभिः।
अश्वैः। चित्रं। भांति। उषसः। चंद्रऽरथाः। अग्रं। यज्ञस्य। बृहतः। नयंतीः। वि। ताः। बाधंते।
तमः। ऊर्म्यायाः। श्रवः। वाजं। इषं। ऊर्जं। वहंतीः। नि। दाशुषे। उषसः। मर्त्याय। मघोनीः। वी

© Dharmartha Trust J&K. Digitized by eGangotri

प० पं०
५

र॰वत्।पत्यमानाः।अर्वः।धाता।विधते।रत्नं।अद्य।इदा।हि।वः।विधते।रत्नं।अस्ति।इदा।
वीराय।दाशुषे।उषसः।इदा।विप्राय।जरते।यत्।उक्था।नि।स्म।माऽवते।वहथ।पु
रा।चित्।इदा।हि।ते।उषः।अद्रिऽसानो इत्यद्रिऽसानो।गोत्रा।गवां।अंगिरसः।गृणं
ति।वि।अर्केण।बिभिदुः।ब्रह्मणा।च।सत्या।नृणां।अभवत्।देवऽहूतिः।उच्छ।दिवः
।दुहितरिति।प्रत्नऽवत्।नः।भरद्वाजऽवत्।विधते।मघोनि।सुऽवीरं।रयिं।गृणते।
रिरीहि।उरुऽगायं।अधि।धेहि।श्रवः।नः।प०।द्या।वपुः।नु।तत्।चिकितुषे।चित्।अ शिव
स्तु।समानं।नाम।धेनु।पत्यमानं।मर्तेषु।अन्यत्।दोहसे।पीपाय।सकृत्।शुक्रं।दुदुहे। ५

© Dharmartha Trust J&K. Digitized by eGangotri

पृश्निः। ऊधः। ये। अग्नयः। न। शोशुचन्। इधानाः। द्विः। यत्। त्रिः। मरुतः। ववृधंत। अरे-
णवः। हिरण्ययासः। एषां। साकं। नृम्णैः। पौंस्येभिः। च। भूवन्। रुद्रस्य। ये। मीळ्हुषः। सं-
ति। पुत्राः। यान्। चो इति। नु। दाधृविः। भरध्यै। विदे। हि। माता। महः। मही। सा। सा। इ-
त्। पृश्निः। सुऽभ्वे। गर्भं। आ। अधात्। न। ये। ईषंते। जनुषः। अया। नु। अंतरिति। संतः।
अवद्यानि। पुनानाः। निः। यत्। दुह्रे। शुचयः। अनु। जोषं। अनु। श्रिया। तन्वं। उक्षमाणाः।
मक्षु। न। येषु। दोहसे। चित्। अयाः। आ। नाम। धृष्णु। मारुतं। दधानाः। न। ये। स्तौनाः।
अयासः। मन्हा। नु। चित्। सुऽदानुः। अव। यासत्। उग्रान्। प० ॥ ७ ॥ ते। इत्। उग्राः। श-

© Dharmartha Trust J&K. Digitized by eGangotri

नास्यवर्तानतरुता ४ लोके वा जोषुतनये ४

प०पं० ६ वसा। धृष्णु ऽ सेनाः। उभे इति। युंजंत। रोदसीइति। सुमेके इति सु ऽ मेके। अध। स्म। एषु। रोद

सी। स्व ऽ शोचिः। आ। अमवत् ऽ सु। तस्थौ। न। रोकः। अनेनः। वः। मरुतः। यामः। अस्तु।

अनश्वः। चित्। यं। अजति। अरथीः। अनवसः। अनभीशुः। रजः ऽ तूः। वि। रोदसीइति। प

थ्याः। याति। साधन्। ०नु। अस्ति। मरुतः। यं। अवथ। वाज ऽ सातौ। ०यं। अपू ऽ सुासः। व्र

जं। दर्ता। पार्ये। अध। द्योः। प्र। चित्रं। अर्कं। गृणते। तुराय। मारुताय। स्व ऽ तवसे। भरध्वं।

ये। सहांसि। सहसा। सहंते। रेजते। अग्ने। पृथिवी। मखेभ्यः। त्विषि ऽ मंतः। अध्वरस्य ऽ इ त्रिव

व। दिद्युत्। तृष्णु ऽ च्यवसः। जुह्वः। न। अग्नेः। अर्चत्रयः। धुनयः। न। वीराः। भ्राजत्। ज ६

© Dharmartha Trust J&K. Digitized by eGangotri

न्मानः। मरुतः। अधृष्टाः। तं। वृधंतं। मारुतं। भ्राजत्ऽऋष्टिं। रुद्रस्य। सूनुं। हवसा।
आ। विवासे। दिवः। शर्धाय। शुचयः। मनीषाः। गिरयः। न। आपः। उग्राः। अस्पृध्रन्।
१९ प०॥८॥ विश्वेषां। वः। सतां। ज्येष्ठऽतमा। गीःऽभिः। मित्रावरुणा। ववृधध्यै। सं।
या। रश्माऽइव। यमतुः। यमिष्ठा। द्वा। जनान्। असमा। बाहुऽभिः। स्वैः। इयं। मत्।
वां। प्र। स्तृणीते। मनीषा। उप। प्रिया। नमसा। बर्हिः। अच्छ। यंतं। नः। मित्रावरुणौ।
अधृष्टं। छर्दिः। यत्। वां। वरूथ्यं। सुदानू इति सुऽदानू। आ। यातं। मित्रावरुणा।
सुऽशस्ति। उप। प्रिया। नमसा। हूयमाना। सं। यौ। अप्नःऽस्थः। अपसाऽइव। जना।

© Dharmartha Trust J&K. Digitized by eGangotri

प.वं. न्।आशुषिः।यतः।चित्रा।यतथः।महि।त्वा।अश्वो।न।या।वाजिना।पूतबंधूइति पूतऽबंधू।ऋता।
७ यत्।गर्भः।अदितिः।भरध्यै।स्वया।महि।महांता।जायमाना।घोरा।मर्ताय।रिपवे।नि।दीध
रिति।दीधः।विश्वो।यत्।वां।मंहना।मंदमाना।क्षत्रं।देवासः।अदधुः।सऽजोषाः।परि।यत्।भू
थः।रोदसी इति।चित्।उर्वी इति।सं।ति।स्पशः।अदब्धासः।अमूराः॥१॥ता।हि।क्षत्रं।धारयेथे
इति।अनु।घून्।दृंहेथे इति।सानुं।उप मात्रऽइव।द्योः।दृब्ढः।न।सेंत्रः।उत।विश्वऽदेवः।भूमिं।आ
।अतान्।द्यां।धासिना।आयोः।ता।वि।मंत्रं।धैथे इति।जठरं।पृणध्यै।आ।यत्।सद्मा।सऽभृतयः
।पृणंति।न।मर्ष्यंते।युवतयः।अवाताः।वि।यत्।पयः।विश्वऽजिन्वा।भरंते।ना।जिह्वया।स ७

© Dharmartha Trust J&K. Digitized by eGangotri

हं।आ।इदं।सुऽमेधाः।आ।यत्।वां।सऽस्वः।अरत्निः।ऋते।भूत्।नत्।वां।महिऽत्वं।घृतऽअन्नौ।अस्तु।
युवं।दाशुषे।वि।चयिष्टं।अंहः।प्र।यत्।वां।मित्रावरुणा।स्पूर्धन्।प्रिया।धाम।युवऽधिता।मिनं
ति।न।ये।देवासः।ओहसा।न।मर्ताः।अयज्ञऽसाचः।अप्यः।न।पुत्राः।वि।यत्।वा।चं।कीस्तासः
भरंते।शंसंति।के।चित्।निऽविदः।मनानाः।आत्।वां।ब्रवाम।सत्यानि।उक्था।नकिः।देवेभिः।
यतथः।महिऽत्वा।अवोः।इत्था।वां।छर्दिषः।अभिष्टौ।युवोः।मित्रावरुणौ।अस्कृधोयु।अनु।य
त्।गावः।स्फुरान्।ऋजिप्यं।धृष्णु।यत्।रणे।वृषणं।युनजन्।॥१०॥श्रुष्टी।वां।यज्ञः।उत्ऽयतः।
सऽजोषाः।मनुष्वत्।वृक्तऽबर्हिषः।यजध्यै।आ।यः।इन्द्रावरुणौ।इषे।अद्य।महे।सुम्नाय।महे।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं.
८

आऽनुवर्त्तन्ता। ता। हि। श्रेष्ठा। देवऽताता। तुजा। शूराणां। शविष्ठा। ता। हि। भूतं। मघोनां। मंहिष्ठा। तुविऽ
शुष्मा। ऋतेन। वृत्रऽतुरा। सर्वऽसेना॥ ता। गृणीहि। नमस्येभिः। शूषैः। सुम्नेभिः। इंद्रावरुणा। च
काना। वज्रेण। अन्यः। शवसा। हंति। वृत्रं। सिसक्ति। अन्यः। वृजनेषु। विप्रः॥ ग्नाः। च। यत्। नरः। च। वा
वृधंत। विश्वे। देवासः। नरां। स्वऽगूर्ताः॥ प्र। एभ्यः। इंद्रावरुणा। महिऽत्वा। द्यौः। च। पृथिवि। भूतं। उर्वी
इति॥ सः। इत्। सुऽदानुः। स्वऽवान्। ऋतऽवा। इंद्रा। यः। वां। वरुणा। दाशति। त्मन्॥ इषा। सः। द्विषः। तरेत्।
दास्वान्। वंसत्। रयिं। रयिऽवतः। च। जनान्॥ ३३॥ यं। युवं। दाश्वऽअध्वराय। देवा। रयिं। धत्थः।
वसुऽमंतं। पुरुऽक्षुं। अस्मे इति। सः। इंद्रावरुणौ। अपि। स्याम। प्र। यः। सनक्ति। वनुषां। अशस्तीः। ८

© Dharmartha Trust J&K. Digitized by eGangotri

उत। नः। सुऽत्रात्रः। देवऽगोपाः। सूरिऽभ्यः। इंद्रावरुणा। रयिः। स्यात्। येषां। शुष्मः। पृतनासु। सह्वान्।
प्र। सद्यः। द्युम्ना। तिरते। ततुरिः। नु। नः। इंद्रावरुणा। गृणाना। पृंक्तं। रयिं। सौश्रवसाय। देवा। इत्था।
गृणंतः। महिनस्य। शर्द्धः। अपः। न। नावा। दुःऽइता। तरेम। प्र। सम्ऽराजे। बृहते। मन्म। नु। प्रियं। अर्च।
देवाय। वरुणाय। सऽप्रथः। अयं। यः। उर्वी इति। महिना। महिऽव्रतः। क्रत्वा। विऽभाति। अजरः। न। शो
चिषा। इंद्रावरुणा। सुतऽपौ। इमं। सुतं। सोमं। पिबतं। मद्यं। धृतऽव्रता। युवोः। रथः। अध्वरं। देवऽ
वीतये। प्रति। स्वसरं। उप। याति। पीतये। इंद्रावरुणा। मधुमत्ऽतमस्य। वृष्णः। सोमस्य। वृष
णा। आ। वृषेथां। इदं। वां। अंधः। परिऽसिक्तं। अस्मे इति। आऽसद्य। अस्मिन्। बर्हिषि। मादयेथां।

© Dharmartha Trust J&K. Digitized by eGangotri

१ पं ॥१८॥ सं। वां। कर्मणा। सं। इषा। हिनोमि। इंद्राविष्णू इति। अपसः। पारे। अस्य। जुषेथां। यज्ञं। द्रविणं।
९ च। धत्तं। अरिष्टैः। नः। पथिऽभिः। पारयंता। या। विश्वासां। जनितारा। मतीनां। इंद्राविष्णू इति। क
लशा। सोमऽधाना। प्र। वां। गिरः। शस्यमानाः। अवंतु। प्र। स्तोमासः। गीयमानासः। अर्कैः। इंद्रा
9 विष्णू इति। मदऽपती इति मदऽपती। मदानां। आ। सोमं। यातं। द्रविणो इति। दधाना। सं। वां। अंज
तु। अक्तुऽभिः। मतीनां। सं। स्तोमासः। शस्यमानासः। उक्थैः। ॥ अभिमातिऽसहः। इंद्राविष्णू इति।
सधऽमादः। वहंतु। जुषेथां। विश्वा। हवना। मतीनां। उप। ब्रह्माणि। शृणुतं। गिरः। मे। इंद्राविष्णू इ
ति। तत्। पनस्याय्यं। वां। सोमस्य। मदे। उरु। चक्रमाथे इति। अकृणुतं। अंतरिक्षं। वरीयः। अप्रथ ९

ओं वामश्वासा३

© Dharmartha Trust J&K. Digitized by eGangotri

उपब्रह्माणि श्टणुतं

तं। जीवसे। नः। रजांसि। इंद्राविष्णू इति। हविषा। वर्धाना। अग्रऽअद्वाना। नमसा। रातऽहव्या। घृ

तासुती इति घृतऽआसुती। द्रविणं। धत्तं। अस्मे इति। सुमुद्रः। स्थः। कलशः। सोमऽधानः। इंद्राविष्णू

इति। पिबतं। मध्वः। अस्य। सोमस्य। दस्रा। जठरं। पृणेथां। आ। वां। अंधांसि। मदिराणि। अग्मन्।

उप। ब्रह्माणि। शृणुतं। हवं। मे। उभा। जिग्यथुः। न। परा। जयेथे इति। न। परा। जिग्ये। कतरः। चन। एनोः। इंद्रः। च। विष्णो इ

ति। यत्। अपस्पृधेथां। त्रेधा। सहस्रं। वि। तत्। ऐरयेथां॥ ३३॥ घृतवती इति घृतऽवती। भुवनानां।

अभिऽश्रिया। उर्वी इति। पृथ्वी इति। मधुदुघे इति मधुऽदुघे। सुऽपेशसा। द्यावापृथिवी इति। वरु

णस्य। धर्मणा। विस्कभिते इति विऽस्कभिते। अजरे इति। भूरिऽरेतसा। असश्चंती इति। भूरि

© Dharmartha Trust J&K. Digitized by eGangotri

पं.पं. धारे इति भूरिऽधारे। पयस्वती इति। घृतं। दुहाते इति। सुऽकृते। शुचिव्रते इति शुचिऽव्रते। राजंती इति। अ
१० स्य। भुवनस्य। रोदसी इति। अस्मे इति। रेतः। सिंचतं। यत्। मनुःऽहितं। यः। वां। ऋजवे। क्रमणाय। रो
दसी इति। मर्तः। ददाश। धिषणे इति। सः। साधति। प्र। प्रऽजाभिः। जायते। धर्मणः। परि। युवोः। सि
क्ता। विषुऽरूपाणि। सऽव्रता। घृतेन। द्यावापृथिवी इति। अभिवृते इत्यभिऽवृते। घृतऽश्रिया। घृ
तऽपृचा। घृतऽवृधा। उर्वी इति। पृथ्वी इति। होतृऽवूर्ये। पुरोहिते इति पुरःऽहिते। ते इति। इत्। विप्राः।
ईळते। सुम्नं। इष्टये। मधु। नः। द्यावापृथिवी इति। मिमिक्षतां। मधुऽश्चुता। मधुदुघे इति मधुऽदु
घे। मधुव्रते इति मधुऽव्रते। दधाने इति। यज्ञं। द्रविणं। च। देवता। महि। श्रवः। वाजं। अस्मे इति। सुऽ १०

10

© Dharmartha Trust J&K. Digitized by eGangotri

वीर्यं। ऊर्जं। नः। द्यौः। च। पृथिवी। च। पिन्वतां। पिता। माता। विश्वऽविदा। सुऽदंससा। संरराणे इति संऽरराणे।
रोदसी इति। विश्वं। शंऽभुवा। सनिं। वाजं। रयिं। अस्मे इति। सं। इन्वतां॥ १४॥ हिरण्यया। बाहू इति। अयंस्त।
सवनाय। सुऽक्रतुः। घृतेन। पाणी इति। अभि। प्रुष्णुते। मखः। युवा। सुऽदक्षः। रजसः। विऽधर्मणि। देवस्य।
वयं। सवितुः। सवीमनि। श्रेष्ठे। स्याम। वसुनः। च। दावने। यः। विश्वस्य। द्विऽपदः। यः। चतुःऽपदः। निऽवेश
ने। प्रऽसवे। च। असि। भूमनः। अदब्धेभिः। सवितरिति। पायुऽभिः। त्वं। शिवेभिः। अद्य। परि। पाहि। नः। गयं।
हिरण्यऽजिह्वः। सुऽविताय। नव्यसे। रक्ष। माकिः। नः। अघऽशंसः। ईशत॥ ० दमूनाः। हिरण्यऽपाणिः। प्र
तिऽदोषं। अस्थात्। अयःऽहनुः। यजतः। मंद्रऽजिह्वः। आ। दाशुषे। सुवति। भूरि। वामं। उत्। ऊं इति। अया।

उदुष्यदेवः सविता २

© Dharmartha Trust J&K. Digitized by eGangotri

पं॰वं॰ न।उपवक्ताऽइव।बाहू इति।हिरण्यया।सविता।सुऽप्रतीका।दिवः।रोहांसि।अरुहत्।पृथिव्याः।अरीर
३३ मत्।पतयत्।कत्।चित्।अभ्वं।वामं।अद्य।सवितः।वामं।ऊं इति।श्वः।दिवेऽदिवे।वामं।अस्मभ्यं।सा
वीः।वामस्य।हि।क्षयस्य।देव।भूरेः।अया।धिया।वामऽभाजः।स्याम॥३५॥इंद्रासोमा।महि।तत्।वां।
महिऽत्वं।युवं।महानि।प्रथमानि।चक्रथुः।युवं।सूर्यं।विविदथुः।युवं।स्वः।विश्वा।तमांसि।अहतं।
निदः।च।इंद्रासोमा।वासयथः।उषसं।उत्।सूर्यं।नयथः।ज्योतिषा।सह।उप।द्यां।स्कंभथुः।स्कंभ
नेन।अप्रथतं।पृथिवीं।मातरं।वि।इंद्रासोमौ।अहिं।अपः।परिऽस्थां।हथः।वृत्रं।अनु।वां।द्यौः।अ
मन्यत।प्र।अर्णांसि।ऐरयतं।नदीनां।आ।समुद्राणि।पप्रथुः।पुरूणि।इंद्रासोमा।पक्वं।आमासु। ३३

© Dharmartha Trust J&K. Digitized by eGangotri

अंतः।नि।गवां।इत्।दधथुः।वक्षणासु।जगृभथुः।अनपिऽनद्धं।आसु।रुशत्।चित्रासु।जगतीषु।अं
तरिति।इंद्रासोमा।युवं।अंग।तरुत्रं।अपत्यऽसाचं।श्रुत्यं।रराथे इति।युवं।शुष्मं।नर्यं।चर्षणिऽभ्यः
सं।विव्यथुः।पृतनाऽसहं।उग्रा॥५॥ यः।अद्रिऽभित्।प्रथमऽजाः।ऋतऽवा।बृहस्पतिः।आंगिरसः।ह
विष्मान्।द्विबर्हाः।ज्मा।प्राघर्मऽसत्।पिता।नः।आ।रोदसी इति।वृषभः।रोरवीति।जनाय।चित्।यः।
ईवते।ऊं इति।लोकं।बृहस्पतिः।देवऽहूतौ।चकार।घ्नन्।वृत्राणि।वि।पुरः।दर्दरीति।जयन्।शत्रून्।अ
मित्रान्।पृत्ऽसु।सहन्।बृहस्पतिः।सं।अजयत्।वसूनि।महः।व्रजान्।गोऽमतः।देवः।एषः।अपः।सि
सासन्।स्वः।अप्रतिऽइतः।बृहस्पतिः।हंति।अमित्रं।अर्कैः॥३ ७॥ सोमारुद्रा।धारयेथां।असुर्यं।प्र।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. वां। इष्टयः। अरं। अश्नुवंतु। दमेऽदमे। सप्त। रत्ना। दधाना। शं। नः। भूतं। द्विऽपदे। शं। चतुःऽपदे। सोमारुद्रा। वि।
१२ वृहतं। विषूचीं। अमीवा। या। नः। गयं। आऽविवेश। आरे। बाधेथां। निःऽऋतिं। पराचैः। अस्मे इति। भद्रा।
सौश्रवसानि। संतु। सोमारुद्रा। युवं। एतानि। अस्मे इति। विश्वा। तनूषु। भेषजानि। धत्तं। अव। स्यतं। मुं-
चतं। यत्। नः। आस्तीत्। तनूषु। बद्धं। कृतं। एनः। अस्मत्। तिग्मऽआयुधौ। तिग्महेती इति तिग्मऽहेती।
सुऽशेवौ। सोमारुद्रौ। इह। सु। मृळतं। नः। प्र। नः। मुंचतं। वरुणस्य। पाशात्। गोपायतं। नः। सुऽमनस्य-
मानाः॥३॥ जीमूतस्यऽइव। भवति। प्रतीकं। यत्। वर्मी। याति। सऽमदां। उपऽस्थे। अनाविद्धया। तन्वा।
जय। त्वं। सः। त्वा। वर्मणः। महिमा। पिपर्तु। धन्वना। गाः। धन्वना। आजिं। जयेम। धन्वना। तीव्राः। सऽ १२

12

© Dharmartha Trust J&K. Digitized by eGangotri

मदः। जयेम। धनुः। शत्रोः। अप॰कामं। कृणोति। धन्वना। सर्वाः। प्र॰दिशः। जयेम। वक्ष्यंतीऽइव। इत्।
आ। गनीगंति। कर्णं। प्रियं। सखायं। परि॰सस्वजाना। योषाऽइव। शिंक्ते। वि॰तता। अधि। धन्वन्।
ज्या। इयं। समने। पारयंती। तेइति। आचरंतीइत्याऽचरंती। समनाऽइव। योषा। माताऽइव। पुत्रं। बि
भृतां। उप॰स्थे। अप। शत्रून्। विध्यतां। संविदानेइति संऽविदाने। आर्त्नीइति। इमेइति। विस्फु
रंतीइति वि॰स्फुरंती। अमित्रान्। बह्वीनां। पिता। बहुः। अस्य। पुत्रः। चिश्चा। कृणोति। समना।
अव॰गत्य। इषु॰धिः। संकाः। पृतनाः। च। सर्वाः। पृष्ठे। नि॰नद्धः। जयति। प्र॰सूतः।।१०।। रथे। ति
ष्ठन्। नयति। वाजिनः। पुरः। यत्र॰यत्र। कामयते। सु॰सारथिः। अभीशूनां। महिमानं। पनाय

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. तामनः।पश्चात्।अनु।यच्छन्ति।रश्मयः।तीव्रान्।घोषान्।कृण्वते।वृषऽपाणयः।अश्वाः।रथेभिः।

३३ सह।वाजयन्तः।अवऽक्रामन्तः।प्रऽपदैः।अमित्रान्।क्षिणन्ति।शत्रून्।अनपऽव्ययन्तः।रथऽवाहनं।

हविः।अस्य।नाम।यत्र।आयुधं।निऽहितं।अस्य।वर्म।तत्र।रथं।उप।रग्मं।सदेम।विश्वाहा।व

13 यं।सुऽमनस्यमानाः।स्वादुऽसंसदः।पितरः।वयःऽधाः।कृच्छ्रेश्रितः।शक्तिऽवंतः।गभीराः।चित्रऽ

सेनाः।इषुऽबलाः।अमृध्राः।सतःऽवीराः।उरवः।व्रातऽसाहाः।ब्राह्मणासः।पितरः।सोम्यासः।शिवे

इति।नः।द्यावापृथिवी इति।अनेहसा।पूषा।नः।पातु।दुःऽइतात्।ऋतऽवृधः।॰।र०।सुऽपर्णं।व

स्ते।मृगः।अस्याः।दन्तः।गोभिः।संऽनद्धा।पतति।प्रऽसूता।यत्र।नरः।सं।च।वि।च।द्रवंति।तत्र। ३३

रक्षामाकिर्नोअघशं
सईशत॥२

© Dharmartha Trust J&K. Digitized by eGangotri

अस्मभ्यं। इषवः। शर्म। यंसन्। ऋजीते। परि। वृङ्धि। नः। अश्मा। भवतु। नः। तनूः। सोमः। अधि। ब्रवीतु।
नः। अदितिः। शर्म। यच्छतु। आ। जंघन्ति। सानु। एषां। जघनान्। उप। जिघ्नते। अश्वऽअजनि। प्रेऽ
चेतसः। अश्वान्। समत्ऽसु। चोदय। अहिःऽइव। भोगैः। परि। एति। बाहुं। ज्यायाः। हेतिं। परिऽबाध
मानः। हस्तऽघ्नः। विश्वा। वयुनानि। विद्वान्। पुमान्। पुमांसं। परि। पातु। विश्वतः। आलऽअक्ता।
या। रुरुऽशीर्ष्णी। अथो इति। यस्याः। अयः। मुखं। इदं। पर्जन्यऽरेतसे। इष्वै। देव्यै। बृहत्। नमः॥ २३॥
अवऽसृष्टा। परा। पत। शरव्ये। ब्रह्मऽसंशिते। गच्छ। अमित्रान्। प्र। पद्यस्व। मा। अमीषां। कं। चन।
न। उत्। शिषः। यत्र। बाणाः। संऽपतन्ति। कुमाराः। विशिखाःऽइव। तत्र। नः। ब्रह्मणः। पतिः। अदि

© Dharmartha Trust J&K. Digitized by eGangotri

पं.पं. तिः।शर्म।यच्छतु।विश्वाहा।शर्म।यच्छतु।मर्माणि।ते।वर्मणा।छादयामि।सोमः।त्वा।राजा।अमृ-
३४ तेन।अनु।वस्तां।उरोः।वरीयः।वरुणः।ते।कृणोतु।जयंतं।त्वा।अनु।देवाः।मदंतु।यः।नः।स्वः।अ-
14 रणः।यः।च।निष्ट्यः।जिघांसति।देवाः।तं।सर्वे।धूर्वंतु।ब्रह्म।वर्म।मम।अंतरं॥२२॥इति षष्ठं मं-
डलं॥ ॥अग्निं।नरः।दीधितिऽभिः।अरण्योः।हस्तऽच्युती।जनयंत।प्रऽशस्तं।दूरेऽदृशं।गृहऽपतिं।
अथर्युं।तं।अग्निं।अस्ते।वसवः।नि।ऋण्वन्।सुऽप्रतिचक्षं।अवसे।कुतः।चित्।दक्षाय्यः।दमे। यः।
आस।नित्यः।प्रऽइद्धः।अग्ने।दीदिहि।पुरः।नः।अजस्रया।सूर्म्या।यविष्ठ।त्वां।शश्वंतः।उप।यं-
ति।वाजाः।प्र।ते।अग्नयः।अग्निऽभ्यः।वरं।निः।सुऽवीरासः।शोशुचंत।द्युऽमंतः।यत्र।नरः।सं २४

© Dharmartha Trust J&K. Digitized by eGangotri

आसते। सुऽजाताः। दाः। नः। अग्ने। धिया। रयिं। सुऽवीरं। सुऽअपत्यं। सहस्य। प्रऽशस्तं। न। यं। यावा। तर

ति। यातुऽमावान्॥ ५॥ उप। यं। एति। युवतिः। सुऽदक्षं। दोषा। वस्तोः। हविष्मती। घृताची। उप। स्वा। ए

नं। अरमतिः। वसुऽयुः॥ विश्वाः। अग्ने। अप। दह। अरातीः। येभिः। तपःऽभिः। अदहः। जरूथं। प्र। निः

ऽस्वरं। चातयस्व। अमीवां॥ आ। यः। ते। अग्ने। इधते। अनीकं। वसिष्ठ। शुक्र। दीदिऽवः। पावक। उतो

इति। नः। एभिः। स्तवथैः। इह। स्याः॥ वि। ये। ते। अग्ने। भेजिरे। अनीकं। मर्ताः। नरः। पित्र्यासः। पुरुऽत्रा।

उतो। नः। एभिः। सुऽमनाः। इह। स्याः॥ इमे। नरः। वृत्रऽहत्येषु। शूराः। विश्वाः। अदेवीः। अभि। सन्तु। मायाः। ये। मे। धि

यं। पनयंत। प्रऽशस्तां॥ १०॥ मा। शूने। अग्ने। नि। सदाम। नृणां। मा। अशेषसः। अवीरता। परि। २

पं.पं. त्वा।प्रजाऽवतीषु।दुर्यासु।दुर्याः।यं।अभ्वी।निसं।उपऽयाति।यज्ञं।प्रजाऽवंतं।सुऽअपत्यं।क्षयं।नः।स्व

१५ ऽजन्मना।शेषसा।वरधानं।पाहि।नः।अग्ने।रक्षसः।अजुष्टात्।पाहि।धूर्तेः।अररुषः।अघऽयोः

त्वा।युजा।पृतनाऽयूंन्।अभि।स्यां।सः।इत्।अग्निः।अग्नीन्।अति।अस्तु।अन्यान्।यत्र।वाजी।

15 तनयः।वीळुऽपाणिः।सहस्रऽपाथाः।अक्षरा।संऽएति।सः।इत्।अग्निः।यः।वनुष्यतः।निऽपाति।सं

ऽएद्धारं।अंहसः।उरुष्यात्।सुऽजातासः।परि।चरंति।वीराः॥२५॥अयं।सः।अग्निः।आऽहुतः।पुरु

त्रा।यं।ईशानः।सं।इत्।इंधे।हविष्मान्।परि।यं।एति।अध्वरेषु।होता।त्वेइति।अग्ने।आऽहवनानि।

भूरि।ईशानासः।आ।जुहुयाम।नित्या।उभा।कृण्वंतः।वहतूइति।मियेधोइमोइति।अग्ने।वीतऽतं १५

© Dharmartha Trust J&K. Digitized by eGangotri

मानि। हव्या। अजस्रः। वक्षि। देवऽतातिं। अच्छ। प्रति। नः। ईं। सुरभीणि। व्यंतु। मा। नः। अग्ने। अवीरते।
परा। दाः। दुःऽवाससे। अमतये। मा। नः। अस्यै। मा। नः। क्षुधे। मा। रक्षसे। ऋतऽवः। मा। नः। दमे। मा। व
ने। आ। जुहूर्थाः। नु। मे। ब्रह्माणि। अग्ने। उत्। शशाधि। त्वं। देव। मघवत्ऽभ्यः। सुसूदः। रातौ। स्याम।
उभयासः। आ। ते। यूयं। पात। स्वस्तिऽभिः। सदा। नः। २१। त्वं। अग्ने। सुऽहवः। रण्वऽसंदृक्। सुऽदीती।
सूनो इति। सहसः। दिदीहि। मा। त्वे इति। सचा। तनये। नित्ये। आ। धक्। मा। वीरः। अस्मत्। नर्यः। वि।
दासीत्। मा। नः। अग्ने। दुःऽभृतये। सचा। एषु। देवऽइद्धेषु। अग्निषु। प्र। वोचः। मा। ते। अस्मान्। दुःऽमत
यः। भृमात्। चित्। देवस्य। सूनो इति। सहसः। नशंत। सः। मर्त्तः। अग्ने। सुऽअनीक। रेवान्। अमर्त्ये।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.पं.

३६

16

यः। आऽजुहोति। हव्यं। सः। देवता। वसुऽवनिं। दधाति। यं। सूरिः। अर्थी। पृच्छमानः। एति। मंहः। नः। अग्ने।
सुवितस्य। विद्वान्। रयिं। सूरिऽभ्यः। आ। वह। बृहंतं। येन। वयं। सहसावन्। मदेम। अविऽक्षितं। सः।
आयुषा। सुऽवीरः। ता। मे। ब्रह्माणि। अग्ने। उत। शशाधि। त्वां। देवाः। मघवत्ऽभ्यः। सुसूदः। राती। स्या
म। उभया। सः। आ। ते। यूयं। पात। स्वस्तिऽभिः। सदा। नः॥ २७॥ इति पंचमाष्टके प्रथमोध्यायः॥ हरिः ॐ
श॥ ओम्॥ जुषस्वैकादश प्रमग्निं वो दश प्रवः आग्नयेनव वैश्वानरीयं तु प्रसम्राजः सप्त प्र वो देवमिंधे वो
धिषकृषो न पंच महानग्न मत्त चं आग्नये वैश्वानरीयं समिधा बृहत्या द्युपसद्याय पंचोना गाय
त्रमेना वो द्वादश प्राग्गाथमग्ने भव सप्त द्वेपदं त्रैष्टुभं त्वेह पंचाधिकेंद्र सुदासः पैजवनस्यां त्याश्वत ३६

© Dharmartha Trust J&K. Digitized by eGangotri

सोदान स्तुतिर्यस्त्रिगमश्वंग एकादश॥ ॐम॥ जुषस्व। नः। संऽइधं। अग्ने। अद्य। शोच। बृहत्। यजतं। धू
मं। ऋऽण्वन्। उप। स्पृश। दिव्यं। सानु। स्तूपैः। सं। रश्मिऽभिः। ततनः। सूर्यस्य। नराशंसस्य। महिमानं।
एषां। उप। स्तोषाम। यजतस्य। यज्ञैः। ये। सुऽक्रतवः। शुचयः। धियंऽधाः। स्वदंति। देवाः। उभयानि।
हव्या। ईळेन्यं। वः। असुरं। सुऽदक्षं। अंतः। दूतं। रोदसीइति। सत्यऽवाचं। मनुष्वत्। अग्निं। मनुना। संऽ
इद्धं। सो। अध्वराय। सदं। इत्। महेम। सपर्यवः। भरमाणाः। अभिऽज्ञु। प्र। वृंजते। नमसा। बर्हिः। अग्नौ।
आऽजुह्वानाः। घृतऽपृष्ठं। पृषत्ऽवत्। अध्वर्यवः। हविषा। मर्जयध्वं। सुऽआध्यः। विदुः। देवऽयंतः। अ
शिश्रयुः। रथऽयुः। देवऽताता। पूर्वीइति। शिशुं। न। मातरा। रिहाणेइति। सं। अग्रुवः। न। समनेषु। अंज

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. न्॥३॥उत। योषणेइति। दिव्येइति। महीइति। नः। उषसानक्ता। [illegible]। सुदुघाऽइव। धेनुः। बर्हिऽसदा।
१० पुरुहूतेइति पुरुऽहूते। मघोनीइति। आ। यज्ञियेइति। सुविताय। श्रयेतां॥ विप्रा। यज्ञेषु। मानु

17

षेषु। कारूइति। मन्ये। वां। जातऽवेदसा। यजध्यै। ऊर्ध्वं। नः। अध्वरं। कृतं। हवेषु। आ। देवे

आभारती
भारतीभिः
सजोषा०
ऋ.कू.४

षु। वनथः। वार्याणि॥ ०॥२॥ अग्निं। वः। देवं। अग्निऽभिः। सऽजोषाः। यजिष्ठं। दूतं। अध्वरे।
कृणुध्वं। यः। मर्त्येषु। निऽध्रुविः। ऋतऽवा। तपुःऽमूर्धा। घृतऽअन्नः। पावकः॥ प्रो
थत्। अश्वः। न। यवसे। अविष्यन्। यदा। महः। संऽवरणात्। वि। अस्थात्। ०। आत्। अस्य। १२
ते। व्रजनं। कृष्णं। अस्ति। उत। यस्य। ते। नवऽजातस्य। वृष्णः। अग्ने। चरंति। अजराः। इधा १०

ओदस्ववातोअनुवाति शोचि २

© Dharmartha Trust J&K. Digitized by eGangotri

नः। अच्छ। द्यां। अरुषः। धूमः। एति। सं॒ऽदूतः। अ॒ग्ने॒। ईयसे। हि। दे॒वान्। वि। यस्य। ते॒। पृ॒थि॒व्यां। पाजः। अश्रेत्।
तृषु। यत्। अन्ना। सं॒ऽअवृक्त। जंभैः। सेनाःऽइव। सृ॒ष्टा। प्रऽसितिः। ते॒। ए॒ति॒। यवं। न। द॒स्म॒। जु॒ह्वा। वि॒वे॒क्षि॒। तं।
इत्। दो॒षा। तं। उ॒षसि। यविष्ठं। अ॒ग्निं। अत्यं। न। म॒र्ज॒यं॒त॒। नरः। नि॒ऽशिशानाः। अतिथिं। अ॒स्य। योनौ। दी॒दा॒-
य। शो॒चिः। आऽहुतस्य। वृष्णः।।३।। सु॒ऽसं॒दृक्। ते॒। सु॒ऽअनी॒क॒। प्रतीकं। वि। यत्। रु॒क्मः। न। रोचसे। उ॒पा॒के।
दि॒वः। न। ते॒। त॒न्य॒तुः। ए॒ति॒। शुष्मः। चि॒त्रः। न। सूरः। प्रति। च॒क्षि॒। भा॒नुं। यथा। वः॒। स्वाहा। अ॒ग्नये। दाशेम।
परि। इळाभिः। घृ॒तवत्ऽभिः। च॒। ह॒व्यैः। तेभिः। नः॒। अ॒ग्ने॒। अमितैः। महःऽभिः। श॒तं। पूः॒ऽभिः। आयसीभिः।
नि। पा॒हि॒। याः। वा॒। ते॒। संति। दा॒शुषे। अधृष्टाः। गिरः। वा॒। याभिः। नृ॒ऽवतीः। उ॒रु॒ष्याः। ताभिः। नः॒। सू॒नो॒।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ पं॰ इति। सहस्रः। नि। पाहि॥ स्मत्। सूरीन्। जरितॄन्। जातऽवेदः। निः। यत्। पूताऽइव। स्वऽधितिः। शुचिः। गात्।

१८ स्वया। रूपा। तन्वा। रोचमानः। आ। यः। मात्रोः। उशेन्यः। जनिष्ट। देवऽयज्याय। सुऽक्रतुः। पावकः। एता। नः।

अग्ने। सौभगा। दिदीहि। अपि। क्रतुं। सुऽचेतसं। वतेम। विश्वा। स्तोतृऽभ्यः। गृणते। च। सं। तु॥ ँ॥ ३॥ प्र। वः। यूयं पात॰

18 शुक्राय। भानवे। भरध्वं। हव्यं। मतिं। च। अग्नये। सुऽपूतं। यः। दैव्यानि। मानुषा। जनूंषि। अंतः। विश्वा।

नि। विद्मना। जिगाति॥ सः। गृत्सः। अग्निः। तरुणः। चित्। अस्तु। यतः। यविष्ठः। अजनिष्ट। मातुः। सं। यः।

वना। युवते। शुचिऽदन्। भूरि। चित्। अन्ना। सं। इत्। अत्ति। सद्यः॥ अस्य। देवस्य। संऽसदि। अनीके। यं।

मर्तासः। श्येतं। जगृभ्रे। नि। यः। गृभं। पौरुषेयीं। उवोच। दुःऽओकं। अग्निः। आयवे। शुशोच॥ अयं। कु १८

© Dharmartha Trust J&K. Digitized by eGangotri

विः। अकविषु। प्रऽचेताः। मर्त्तेषु। अग्निः। अमृतः। नि। धायि। सः। मा। नः। अत्र। जुहुरः। सहस्वः। सदा। त्वेइति।
सुऽमनसः। स्याम। आ। यः। योनिं। देवऽकृतं। ससाद। क्रत्वा। हि। अग्निः। अमृतान्। अतारीत्। तं। ओ
षधीः। च। वनिनः। च। गर्भं। भूमिः। च। विश्वऽधायसं। बिभर्ति॥ ५॥ ईशे। हि। अग्निः। अमृतस्य। भू
रेः। ईशे। रायः। सुऽवीर्यस्य। दातोः। मा। त्वा। वयं। सहसाऽवन्। अवीराः। मा। अप्सवः। परि। सदाम।
मा। अदुवः। परिऽसद्यं। हि। अरणस्य। रेक्णः। नित्यस्य। रायः। पतयः। स्याम। न। शेषः। अग्ने। अ
न्यऽजातं। अस्ति। अचेतानस्य। मा। पथः। वि। दुक्षः। नहि। ग्रभाय। अरणः। सुऽशेवः। अन्यऽउदर्यः।
मनसा। मंतवै। ऊंइति। अध। चित्। ओकः। पुनः। इत्। सः। एति। आ। नः। वाजी। अभीषाट्। एतु। न

© Dharmartha Trust J&K. Digitized by eGangotri

त्वमग्ने व॰ सत्या॰ एता नो अग्ने॰ विश्वास्त्वो॰ १ कू २

प॰पं॰ व्यः॥ ३॥ ५॥ प्र। अग्नये। तवसे। भर्ध्वं। गिरं। दिवः। अरतये। पृथिव्याः। यः। विश्वेषां। अमृतानां। उपऽ
३० स्थे। वैश्वानरः। वृवृधे। जागृवत्ऽभिः। पृष्टः। दिवि। धायि। अग्निः। पृथिव्यां। नेता। सिंधूनां। वृष
भः। स्तियानां। सः। मानुषीः। अभि। विशः। वि। भाति। वैश्वानरः। ववृधानः। वरेण। त्वत्। भिया। विशः। आ
यन्। असिक्नीः। असमनाः। जहतीः। भोजनानि। वैश्वानर। पूरवे। शोशुचानः। पुरः। यत्। अग्ने। दर
यन्। अदीदेः। तव। त्रिऽधातु। पृथिवी। उत। द्यौः। वैश्वानर। व्रतं। अग्ने। सचंत। त्वं। भासा। रोदसी इति।
आ। ततंथ। अजस्रेण। शोचिषा। शोशुचानः। त्वां। अग्ने। हरितः। वावशानाः। गिरः। सचंते। धुनयः।
घृताचीः। पतिं। कृष्टीनां। रथ्यं। रयीणां। वैश्वानरं। उषसां। केतुं। अह्नां॥ ७॥ त्वे इति। असुर्यं। वसवः। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

नि। ऋण्वन्। क्रतुं। हि। ते। मित्रऽमहः। जुषंत। त्वं। दस्यून्। ओकसः। अग्ने। आजः। उरु। ज्योतिः। जनयन्। आर्या
य। सः। जायमानः। परमे। विऽओमन्। वायुः। न। पाथः। परि। पासि। सद्यः। त्वं। भुवना। जनयन्। अभि।
क्रन्। अपत्याय। जातऽवेदः। दशस्यन्। तां। अग्ने। अस्मे इति। इषं। आ। ईरयस्व। वैश्वानर। द्युऽमतीं।
जातऽवेदः। यया। राधः। पिन्वसि। विश्वऽवार। पृथु। श्रवः। दाशुषे। मर्त्याय। तं। नः। अग्ने। मघवत्ऽभ्यः।
पुरुऽक्षुं। रयिं। नि। वाजं। श्रुत्यं। युवस्व। वैश्वानर। महि। नः। शर्म। यच्छ। रुद्रेभिः। अग्ने। वसुऽभिः। सऽजो
षाः। ९। प्र। सम्ऽराजः। असुरस्य। प्रऽशस्तिं। पुंसः। कृष्टीनां। अनुऽमाद्यस्य। इंद्रस्यऽइव। प्र। तवसः। कृ
तानि। वंदे। दारुं। वंदमानः। विवक्मि। कविं। केतुं। धासिं। भानुं। अद्रेः। हिन्वंति। शं। राज्यं। रोदस्योः। पु

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. रंऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि । नि । अक्रतून् । ग्रथिनः । मृध्रऽवाचः ।
२० पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् । प्रऽप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् ।
अयज्यून् । यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृऽतमः । शचीभिः । तं । ईशानं । वस्वः । अ-
20 ग्निं । गृणीषे । अनानतं । दमयंतं । पृतन्यून् । यः । देह्यः । अनमयत् । वधऽस्नैः । यः । अर्यऽपत्नीः । उषसः ।
चकार । सः । निऽरुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलिऽहृतः । सहःऽभिः । यस्य । शर्मन् । उप ।
विश्वे । जनासः । एवैः । तस्थुः । सुऽमतिं । भिक्षमाणाः । वैश्वानरः । वरं । आ । रोदस्योः । आ । अग्निः । ससा-
द । पित्रोः । उपऽस्थं । आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्ऽइता । सूर्यस्य । आ । समुद्रात् । अव- २०

© Dharmartha Trust J&K. Digitized by eGangotri

ह

रात्। आ। परस्मात्। आ। अग्निः। ददे। दिवः। आ। पृथिव्याः॥ ५॥ प्र। वः। देवं। चित्रा। ससानं। अग्निं।
अश्वं। न। वाजिनं। हिषे। नमः ऽभिः। भव। नः। दूतः। अध्वरस्य। विद्वान्। त्मना। देवेषु। विविदे। मितऽ
द्रुः। आ। याहि। अग्ने। पथ्याः। अनु। स्वाः। मन्द्रः। देवानां। सख्यं। जुषाणः। आ। सानु। शुष्मैः। नदयन्।
पृथिव्याः। जंभेभिः। विश्वं। उशधक्। वनानि। प्राचीनः। यज्ञः। सुऽधितं। हि। बर्हिः। प्रीणीते। अग्निः।
ईळितः। न। होता। आ। मातरा। विश्ववारे इति विश्वऽवारे। हुवानः। यतः। यविष्ठ। जज्ञिषे। सुऽशे
वः। सद्यः। अध्वरे। रथिरं। जनंत। मानुषासः। विऽचेतसः। यः। एषां। विशां। अधायि। विश्पतिः।
दुरोणे। अग्निः। मंद्रः। मधुऽवचाः। ऋतऽवा। असादि। वृतः। वह्निः। आऽजगन्वान्। अग्निः। ब्रह्मा।

© Dharmartha Trust J&K. Digitized by eGangotri

ऋ॰पं॰ रुऽसदने।विऽधर्ता।द्यौः।च।या।पृथिवी।वरुधाते इति।आ।यं।होता।यजति।विश्वऽवारं।त्वं।द्युम्नेभिः

२१ ।विश्वं।आ।अतिरंत।मंत्रैः।ये।वा।अरं।नर्याः।अतक्षन्।प्र।ये।विशः।तिरंत।श्रोषमाणाः।आ।ये।मे।

अस्य।दीधयन्।ऋतस्य।नु।त्वां।अग्ने।ईमहे।वसिष्ठाः।ईशानं।सूनो इति।सहसः।वसूनां।इषं।स्तो

पू॰पं॰ तृऽभ्यः।मघवत्ऽभ्यः।आनट्।गे।१०।इंधे।राजा।सं।अर्यः।नमःऽभिः।यस्य।प्रतीकं।आऽहुतं।घृतेन।

नरः।हव्येभिः।ईळते।सऽबाधः।आ।अग्निः।अग्रे।उषसां।अशोचि।अयं।ऊं इति।स्यः।सु।महान्।

अवेदि।होता।मंद्रः।मनुषः।यह्वः।अग्निः।वि।भाः।अकारित्यकः।सस्त्वजानः।पृथिव्यां।कृष्णःऽपविः।

ओषधीभिः।ववक्षे।कया।नः।अग्ने।वि।वसः।सुऽवृक्तिं।कां।ऊं इति।स्वधां।ऋणवः।शस्यमानः। २१

© Dharmartha Trust J&K. Digitized by eGangotri

कदा। भुवेम। पतयः। सुऽदत्र। रायः। वंतारः। दुस्तरस्य। साधोः। प्रऽप्र। अयं। अग्निः। भरतस्य। शृण्वे। वि। य
त्। सूर्यः। न। रोचते। बृहत्। भाः। अभि। यः। पूरुं। पृतनासु। तस्थौ। द्युतानः। दैव्यः। अतिथिः। शुशोच। अ
सन्। इत्। त्वे इति। आऽहवनानि। भरि। भुवः। विश्वेभिः। सुऽमनाः। अनीकैः। स्तुतः। चित्। अग्ने। शृण्विषे।
गृणानः। स्वयं। वर्धस्व। तन्वं। सुऽजात। इदं। वचः। शतऽसाः। संऽसहस्रं। उत्। अग्नौ। जनिषीष्ट। द्विऽबर्हाः। ये
शंयँस्तोतृभ्य आपयेभवा ति ५ द्युऽमत्। अमीवऽचातनं। रक्षःऽहा। ६।३। अबोधि। जारः। उषसां। उपऽस्थात्। होता। मंद्रः। कविऽतमः। नूँत्वामग्न०
पावकः। दधाति। केतुं। उभयस्य। जंतोः। हव्या। देवेषु। द्रविणं। सुकृत्ऽसु। सः। सुऽक्रतुः। यः। वि। दुरः। पणी ऋकू १
नां। पुनानः। अर्कं। पुरुऽभोजसं। नः। होता। मंद्रः। विशां। दमूनाः। तिरः। तमः। ददृशे। राम्याणां। अमूरः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. कविः। अदितिः। विवस्वान्। सुऽसंसत्। मित्रः। अतिथिः। शिवः। नः। चित्रऽभानुः। उषसां। भाति। अ
२२ ग्रे। अपां। गर्भः। प्रऽस्वः। आ। विवेश। ईळेन्यः। वः। मनुषः। युगेषु। समनऽगाः। अशुचत्। जातऽवे
22 दाः। सुऽसंदृशा। भानुना। यः। विऽभाति। प्रति। गावः। सम्ऽइधानं। बुधंत। अग्ने। याहि। दूत्यं। मा।
रिषण्यः। देवान्। अच्छ। ब्रह्मऽकृता। गणेन। सरस्वतीं। मरुतः। अश्विना। अपः। यक्षि। देवान्।
रत्नऽधेयाय। विश्वान्। त्वां। अग्ने। सम्ऽइधानः। वसिष्ठः। जरूथं। हन्। यक्षि। राये। पुरंऽधिं। पुरुऽ
यूपं०६ नीथा। जातऽवेदः। जरस्व। ॥१२॥ उषः। न। जारः। पृथु। पाजः। अश्रेत्। दविद्युतत्। दीद्यत्। शोशु
चानः। वृषा। हरिः। शुचिः। आ। भाति। भासा। धियः। हिन्वानः। उशतीः। अजीगरिति। स्वः। न। व २२

© Dharmartha Trust J&K. Digitized by eGangotri

स्तोः।उषसो।अरोचि।यज्ञं।तन्वानाः।उशिजः।न।मन्म।अग्निः।जन्मानि।देवः।आ।वि।विद्वान्।द्रवत्।दू
तः।देवऽयावा।वनिष्ठः।अच्छ।गिरः।मतयः।देवऽयन्तीः।अग्निं।यन्ति।द्रविणं।भिक्षमाणाः।सुऽसंदृशं।
सुऽप्रतीकं।सुऽअञ्चं।हव्यऽवाहं।अरतिं।मानुषाणां।इन्द्रं।नः।अग्ने।वसुऽभिः।सऽजोषाः।रुद्रं।रुद्रेभिः।
आ।वह।बृहन्तं।आदित्येभिः।अदितिं।विश्वऽजन्यां।बृहस्पतिं।ऋक्वऽभिः।विश्वऽवारं।मन्द्रं।होतारं।उ
शिजः।यविष्ठं।अग्निं।विशः।ईळते।अध्वरेषु।सः।हि।क्षपाऽवान्।अभवत्।रयीणां।अतन्द्रः।दूतः।य
जथाय।देवान्॥३॥महान्।असि।अध्वरस्य।प्रऽकेतः।न।ऋते।त्वत्।अमृताः।मादयन्ते।आ।विश्वेभिः।
सऽरथं।याहि।देवैः।नि।अग्ने।होता।प्रथमः।सद।इह।त्वां।ईळते।अजिरं।दूत्याय।हविष्मन्तः।सदं।इ

© Dharmartha Trust J&K. Digitized by eGangotri

ॐ ग्निरीशेवसूतोऽ

प.पं. त्।मानुषासः।यस्य।देवैः।आ।असदः।बर्हिः।अग्ने।अहानि।अस्मै।सुऽदिनां।भवंति।त्रिः।चित्।अक्तोः।
२३ प्र।चिकितुः।वसूनि।त्वे इति।अंतरिति।दाशुषे।मर्त्याय।मनुष्वत्।अग्ने।इह।यक्षि।देवान्।भव।नः।दूतः।अभि
23 शस्तिऽपावा॥३॥अध्वरस्य।अग्निः।विश्वस्य।हविषः।कृतस्य।क्रतुं।हि।अस्य।वसवः।जुषंत।अथ।देवाः।
दधिरे।हव्यऽवाहं।आ।अग्ने।वह।हविःऽअद्याय।देवान्।इंद्रऽज्येष्ठासः।इह।मादयंतां।इमं।यज्ञं।दिवि।देवे
यू.ये.०५ षु।धेहि॥४॥अगन्म।महा।नमसा।यविष्ठं।यः।दीदाय।संऽइद्धः।स्वे।दुरोणे।चित्रऽभानुं।रोदसी इति।
अंतरिति।उर्वी इति।सुऽआहुतं।विश्वतः।प्रत्यंचं॥सः।मह्ना।विश्वा।दुःऽइतानि।सह्वान्।अग्निः।स्तवे।दमे।आ।
जातऽवेदाः।सः।नः।रक्षिषत्।दुःऽइतात्।अवद्यात्।अस्मान्।गृणतः।उत।नः।मघोनः॥त्वं।वरुणः।उत।मि २३

© Dharmartha Trust J&K. Digitized by eGangotri

पूर्यं०

त्रः। अग्ने। त्वां। वर्द्धन्ति। मतिऽभिः। वसिष्ठाः। स्वे इति। वसु। सुऽसननानि। संतु॥ ॥३५॥ प्र। अग्नये। विश्वऽशु
चे। धियंऽधे। असुरऽघ्ने। मन्म। धीतिं। भरध्वं। भरे। हविः। न। बर्हिषि। प्रीणानः। वैश्वानराय। यतये। मती
नां॥ त्वं। अग्ने। शोचिषा। शोशुचानः। आ। रोदसी इति। अपृणाः। जायमानः। त्वं। देवान्। अभिऽशस्तेः। अ
मुंचः। वैश्वानर। जातऽवेदः। महिऽत्वा॥ जातः। यत्। अग्ने। भुवना। वि। अख्यः। पशून्। न। गोपाः। इर्यः। प
पूर्यं०५ रिऽज्मा॥ वैश्वानर। ब्रह्मणे। विंद। गातुं॥ ॥१॥ सं। इधा। जातऽवेदसे। देवाय। देवहूतिऽभिः। हविःऽभिः।
शुक्रऽशोचिषे। नमस्विनः। वयं। दाशेम। अग्नये॥ वयं। ते। अग्ने। संऽइधा। विधेम। वयं। दाशेम। सुऽस्तु
ती। यजत्र॥ वयं। घृतेन। अध्वरस्य। होतः। वयं। देव। हविषा। भद्रऽशोचे॥ आ। नः। देवेभिः। उप। देवऽहूतिं।

© Dharmartha Trust J&K. Digitized by eGangotri

यूयं०

प.पं. अग्ने। याहि। वषट्ऽकृतिं। जुषाणः। तुभ्यं। देवाय। दाशतः। स्याम। ॥ २ ॥ उप। सद्याय। मीळ्हुषे। आस्ये।
२५ जुहुत। हविः। यः। नः। नेदिष्ठं। आप्यं। यः। पंच। चर्षणीः। अभि। निऽससाद। दमेऽदमे। सः। नः। वेदः। अमा = कविर्गृह पतिर्युवा२
त्यं। अग्निः। रक्षतु। विश्वतः। उत। अस्मान्। पातु। अंहसः। नवं। नु। स्तोमं। अग्नये। दिवः। श्येनाय। जीजनं।
24 वस्वः। कुवित्। वनाति। नः। स्पार्हाः। यस्य। श्रियः। दृशा। रयिः। वीरऽवतः। यथा। अग्ने। यज्ञस्य। शोचतः।
॥ ३ ॥ सः। इमां। वेतु। वषट्ऽकृतिं। अग्निः। जुषत। नः। गिरः। यजिष्ठः। हव्यऽवाहनः। नि। त्वा। नक्ष्य। वि
श्पते। द्युऽमंतं। देव। धीमहि। सुऽवीरं। अग्ने। आऽहुत। क्षपः। उस्रः। च। दीदिहि। सुऽअग्नयः। त्वया। वयं।
सुऽवीरः। त्वं। अस्मऽयुः। उप। त्वा। सातये। नरः। विप्रासः। यंति। धीतिऽभिः। उप। अक्षरा। सहस्रि २५

© Dharmartha Trust J&K. Digitized by eGangotri

णी। अग्निः। रक्षांसि। सेधति। शुक्रऽशोचिः। अमर्त्यः। शुचिः। पावकः। ईड्यः॥ १०॥ सः। नः। राधांसि। आ।
भर। ईशानः। सहसः। यहो इति। भगः। च। दातु। वार्यं। त्वं। अग्ने। वीरऽवत्। यशः। देवः। च। सविता। भगः।
दितिः। च। दाति। वार्यं। अग्ने। रक्ष। नः। अंहसः। प्रति। स्म। देव। रिषतः। तपिष्ठैः। अजरः। दह। अध। मही।
नः। आयसी। अनाधृष्टः। नृऽपीतये। पूः। भव। शतभुजिः।० दोषाऽवस्तः। अघऽयतः। दिवा। नक्तं। त्वन्नः पाह्यं
अदाभ्य॥ २०॥ एना। वः। अग्निं। नमसा। ऊर्जः। नपातं। आ। हुवे। प्रियं। चेतिष्ठं। अरतिं। सुऽअध्वरं। हसो ४
विश्वस्य। दूतं। अमृतं। सः। योजते। अरुषा। विश्वऽभोजसा। सः। दुद्रवत्। सुऽआहुतः। सुऽब्रह्मा। य
ज्ञः। सुऽशमी। वसूनां। देवं। राधः। जनानां। उत। अस्य। शोचिः। अस्थात्। आऽजुह्वानस्य। मीळ्हुषः।

© Dharmartha Trust J&K. Digitized by eGangotri

त्वं। हि। रत्नऽधाः। असि॥ ४

५-वं. उत्। धूमासः। अरुषासः। दिविऽस्पृशः। सं। अग्निं। इंधते। नरः॥ त्वां। दूतं। कृण्महे। यशःऽतमं। देवान्।
२५ आ। वीतये। वह। विश्वाः। सूनो इति। सहसः। मर्तऽभोजना। रास्व। तत्। यत्। त्वा। ईमहे। त्वं। अग्ने। गृ
हऽपतिः। त्वं। होता। नः। अध्वरे। त्वं। पोता। विश्वऽवार। प्रऽचेताः। यक्षि। वेषि। च। वार्यं। कृधि। रत्नं। यजमा
नाय। सुक्रतो इति सुऽक्रतो। ॰ आ। नः। ऋते। शिशीहि। विश्वं। ऋत्विजं। सुऽशंसः। यः। च। दक्षते॥ २१॥
सुः त्वे इति। अग्ने। आऽहुत। प्रियासः। संतु। सूरयः। यंतारः। ये। मघऽवानः। जनानां। ऊर्वान्। दयंत। गोनां।
यस्यां। इळा। घृतऽहस्ता। दुरोणे। आ। अपि। प्राता। निऽसीदति। तान्। त्रायस्व। द्रुहः। निदः। [illegible]। य
च्छ। नः। शर्म। दीर्घऽश्रुत्॥ सः। मंद्रया। च। जिह्वया। वह्निः। आसा। विदुःऽतरः। अग्ने। रयिं। मघवत्ऽ २५

सहस्य।

© Dharmartha Trust J&K. Digitized by eGangotri

ध्यः। नः। आ। वह। हव्यऽदातिं। च। सूदय। ये। राधांसि। ददति। अश्व्या। मघा। कामेन। श्रवसः। महः। ता। नः। अंहसः। पिपृहि। पर्तृऽभिः। त्वं। शता। पूःऽभिः। यविष्ठ्य। देवः। वः। द्रविणःऽदाः। पूर्णां। विवष्टि। आऽसिचं। उत। वा। सिंचध्वं। उप। वा। पृणध्वं। आत्। इत्। वः। देवः। ओहते। तं। होतारं। अध्वरस्य। प्रऽचेतसं। वह्निं। देवाः। अकृण्वत। दधाति। रत्नं। विधते। सुऽवीर्यं। अग्निः। जनाय। दाशुषे। १२। अग्ने। भव। सुऽसमिधा। संऽइद्धः। उत। बर्हिः। उर्विया। वि। स्तृणीतां। उत। द्वारः। उशतीः। वि। श्रयंतां। उत। देवान्। उशतः। आ। वह। इह। अग्ने। वीहि। हविषा। यक्षि। देवान्। सुऽअध्वरा। कृणुहि। जातऽवेदः। सुऽअध्वरा। करति। जातऽवेदाः। यक्षत्। देवान्। अमृतान्। पिप्रयत्। च। वं। स्वा। विश्वा। वार्याणि। प्रचेत इति प्रऽचेतः। सत्याः। भवंतु। आऽशिषः। नः। अद्य। त्वां।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. ऊं इति।ते।दधिरे।हव्यऽवाहं।देवासः।अग्ने।ऊर्जः।आ।नपातं।ते।ते।देवाय।दाशतः।स्याम।महः।नः।रत्ना।

२६ विऽदधः।इयानः॥२५॥त्वे इति।ह।यत्।पितरः।चित्।नः।इंद्र।विश्वा।वामा।जरितारः।असन्वन्।त्वे इति।गा

वः।सुऽदुघाः।त्वे इति।हि।अश्वाः।त्वं।वसु।देवऽयते।वनिष्ठः।राजाऽइव।हि।जनिऽभिः।क्षेषि।एव।अव।द्युऽ

26 भिः।अभि।विदुः।कविः।सन्।पिशा।गिरः।मघऽवन्।गोभिः।अश्वैः।त्वाऽयतः।शिशीहि।राये।अस्मान्।

इमाः।ऊं इति।त्वा।पस्पृधानासः।अत्र।मंद्राः।गिरः।देवऽयंतीः।उप।स्थुः।अर्वाची।ते।पथ्या।रायः।ए

तु।स्याम।ते।सुऽमतौ।इंद्र।शर्मन्।धेनुं।न।त्वा।सुऽयवसे।दुधुक्षन्।उप।ब्रह्माणि।ससृजे।वसिष्ठः।त्वां।

इत्।मे।गोःऽपतिं।विश्वः।आह।आ।नः।इंद्रः।सुऽमतिं।गंतु।अच्छ।अर्णांसि।चित्।पप्रथाना।सुऽदा २६

© Dharmartha Trust J&K. Digitized by eGangotri

सः । इंद्रः । गाधानि । अकृणोत् । सुऽपारा । शर्द्धंतं । शिम्युं । उचथस्य । नव्यः । शापं । सिंधूनां । अकृणोत् । अश
स्तीः ॥ २५ । पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निऽशिताः । अपिऽइव । श्रुष्टिं । चक्रुः ।
भृगवः । द्रुह्यवः । च । सखा । सखायं । अतरत् । विषूचोः । आ । पक्थासः । भलानसः । भनंत । आ । अलि
नासः । विषाणिनः । शिवासः । आ । यः । अनयत् । सधऽमाः । आर्यस्य । गव्या । तृत्सुऽभ्यः । अजगन् । यु
धा । नॄन् । दुःऽआध्यः । अदितिं । स्रेवयंतः । अचेतसः । वि । जगृभ्रे । परुष्णीं । मन्हा । अविव्यक् । पृथिवीं ।
पत्यमानः । पशुः । कविः । अशयत् । चायमानः । ईयुः । अर्थं । न । निऽअर्थं । परुष्णीं । आशुः । चन । इत् । अ
भिऽपित्वं । जगाम । सुऽदासे । इंद्रः । सुऽतुकान् । अमित्रान् । अरंधयत् । मानुषे । वध्रिऽवाचः । ईयुः । गावः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ नायवंसाल। अगोपाः। यथा। कृतं। अभि। मित्रं। चितासः। पृश्निऽगावः। पृश्निंऽनिप्रेषितासः। श्रुष्टिं। चक्रुः।
२७ निःऽयुतः। रंत। नृः। चा। ... एकं। चायतः। विंशतिं। च। श्रवस्या। वैकर्णयोः। जनान्। राजा। नि। अस्तरित्य
स्तः। दस्मः। ना। सद्मन्। नि। शिशानि। बर्हिः। शूरः। सर्गं। अकृणोत्। इंद्रः। एषां। अधा। श्रुतं। कवषं। वृद्धं
अपऽसु। अनु। दुह्युं। नि। वृणक्। वज्रऽबाहुः। वृणानाः। अत्र। सख्याय। सख्यं। त्वा। यंतः। ये। अम
दन्। अनु। त्वा। वि। सद्यः। विश्वा। दृंहिता। नि। एषां। इंद्रः। पुरः। सहसा। सप्त। दर्दरिति। दर्द्ः। वि। आनव
स्य। तृत्सवे। गयं। भाक्। जेष्म। पूरुं। विदथे। मृध्रऽवाचं। नि। गव्यवः। अनवः। द्रुह्यवः। च। षष्टिः। शता।
सुसुपुः। षट्। सहस्रा। षष्टिः। वीरासः। अधि। षट्। दुःऽयुवि। विश्वा। इत्। इंद्रस्य। वीर्या। कृतानि। इंद्रं २७

© Dharmartha Trust J&K. Digitized by eGangotri

णा। एत। तस्य। वः। वेविषाणाः। आपः। न। सृष्टाः। अधवंत। नीचीः। दुःऽमित्रासः। प्रकलऽवित्। मिमानाः।
जहुः। विश्वानि। भोजना। सुऽदासे॥ १५॥ अर्द्धं। वीरस्य। शृतऽपां। अनिंद्रं। परा। शर्द्धंतं। नुनुदे। अ
भि। क्षां। इंद्रः। मन्युं। मन्युऽम्यः। मिमाय। भेजे। पथः। वर्तनिं। पत्यमानः। आध्रेण। चित्। तत्। ऊं इति।
एकं। चकार। सिंह्यं। चित्। पेत्वेन। जघान। अव। स्रक्तीः। वेश्या। अवृश्चत्। इंद्रः। प्र। अयच्छत्। विश्वा।
भोजना। सुऽदासे॥ शश्वंतः। हि। शत्रवः। ररधुः। ते। भेदस्य। चित्। शर्द्धतः। विंद। रंधिं। मर्तान्। एनः।
स्तुवतः। यः। कृणोति। तिग्मं। तस्मिन्। नि। जहि। वज्रं। इंद्र। आवत्। इंद्रं। यमुना। तृत्सवः। च। अत्र। प्र।
भेदं। सर्वऽताता। मुषायत। अजासः। च। शिग्रवः। यक्षवः। च। बलिं। शीर्षाणि। जभ्रुः। अश्व्यानि।

© Dharmartha Trust J&K. Digitized by eGangotri

म

प.पं. नातेऽइंद्र। सुऽमृतयः। ना। रायः। सुंऽचक्षाः। पूर्वीः। उरुऽबसंः। ना। नूत्नाः। देवकं। चित्। मान्यमानं। जघंथ। अव।
२८ त्मना। बृहतः। शंबरं। भेत्॥२॥ ग्ना। ये। गृहात्। अमंदुः। त्वाऽया। पराऽशरः। शतऽयातुः। वसिष्ठः। ना।
ते। भोजस्य। सख्यं। मृषंत। अध। सूरिऽभ्यः। सुऽदिना। वि। उच्छान्। द्वेइति। नप्तुः। देवऽवंतः। शतेइति।
28 गोः। द्वा। रथा। वधूऽमंता। सुऽदासः। अर्हन्। अग्ने। पैजऽवनस्य। दानं। होताऽइव। सद्म। परि। एमि। रे
भन्। चत्वारः। मा। पैजऽवनस्य। दानाः। स्मत्ऽदिष्टयः। कृशनिनः। निःरेकाः। ऋज्रासः। मा। पृथिविऽस्थाः।
सुऽदासः। तोकं। तोकाय। श्रवसे। वहंति। यस्य। श्रवः। रोदसीइति। अंतः। उर्वीइति। शीर्ष्णेऽशी
र्ष्णे। विऽबभाज। विऽभक्ता। सप्त। इत्। इंद्रं। न। स्रवतः। गृणंति। नि। युध्यामधिं। अशिशात्। अभीके। २८

© Dharmartha Trust J&K. Digitized by eGangotri

त्वं ह त्यदिंद्र

इमं। नरः। मरुतः। सश्चत। अनु। दिवः ऽ दासं। न। पितरं। सुऽदासः। अविष्टन। पैजऽवनस्य। केतं। दुः ऽ नशं। क्षत्रं। अजरं। दुवःऽयु॥२५॥ यः। तिग्मऽशृंगः। वृषभः। न। भीमः। एकः। कृष्टीः। च्यवयति। प्र। विश्वाः। यः। शश्वतः। अदाशुषः। गयस्य। प्रऽयंता। असि। सुस्विऽतराय। वेदः॥ कुत्सं। आवः। शुश्रूषमाणः। तन्वा। सऽमर्ये। दासं। यत्। शुष्णं। कुयवं। नि। अस्मै। अरंधयः। आर्जुनेयाय। शिक्षन्। त्वं। धृष्णो इति। धृषता। वीतऽहव्यं। प्र। आवः। विश्वाभिः। ऊतिऽभिः। सुऽदासं। प्र। पौरुऽकुत्सिं। त्रसदस्युं। आवः। क्षेत्रऽसाता। वृत्रऽहत्येषु। पूरुं॥ त्वं। नृऽभिः। नृऽमनः। देवऽवीतौ। भूरीणि। वृत्रा। हरिऽअश्व। हंसि। त्वं। नि। दस्युं। चुमुरिं। धुनिं। च। अस्वापयः। दभीतये। सुऽहंतु॥ तव। च्यौत्नानि। वज्रऽहस्त। तानि। नव। यत्। पुरः।

© Dharmartha Trust J&K. Digitized by eGangotri

सनाता तइंद्र १

प॰पं॰ नवतिं।च।सद्यः।निःऽवेशने।शतऽतमा।अविवेषीः।अहन्।वृत्रं।नमुचिं।उत।अहन्॥५॥ँभोजना

२९ नि।रातऽहव्याय।दाशुषे।सुऽदासे।वृष्णे।ते।हरी इति।वृषणा।युनज्मि।व्यंतु।ब्रह्माणि।पुरुऽशाक।वाजं।

29 मा।ते।अस्यां।सहसाऽवन्।परिष्टौ।अघाय।भूम।हरिऽवः।पराऽदै।त्रायस्व।नः।अवृकेभिः।वरूथैः।त

व।प्रियासः।सूरिषु।स्याम॥प्रियासः।इत्।ते।मघऽवन्।अभिष्टौ।नरः।मदेम।शरणे।सखायः।नि।तु

र्वशं।नि।याद्वं।शिशीहि।अतिथिऽग्वाय।शंस्यं।करिष्यन्॥सद्यः।चित्।नु।ते।मघऽवन्।अभिष्टौ।नरः।

शंसंति।उक्थऽशासः।उक्था।ये।ते।हवेभिः।वि।पणीन्।अदाशन्।अस्मान्।वृणीष्व।युज्याय।तस्मै।

एते।स्तोमाः।नरां।नृऽतम।तुभ्यं।अस्मद्र्यंचः।ददतः।मघानि।तेषां।इंद्र।वृत्रऽहत्ये।शिवः।भूः।सखा। २९

© Dharmartha Trust J&K. Digitized by eGangotri

यू॰यं॰

वा।भरेः।अविता।वानृणां।नु।इंद्र।शूर।स्तवमानः।ऊती।ब्रह्मऽजूतः।तन्वा।वावृधस्व।उप।नः।वाजा।न्।

मिमीहि।उप।स्तीन्।ऊ॰॥इति पंचमाष्टके द्वितीयोध्यायः॥ॐ म॥उग्रोमादरशासाविपिबनयंवैराजम

तेस्यामुदुषस्योन्निरातेनसोमःपंचेंद्रंनरोब्रह्मणोयंसोमआनःप्रयोद्वादशगायत्रंत्रिविराकंतंमोषुस

माधिकाप्रगाथंतृतीयाद्विपदासोदासेरग्नौप्रक्षिप्यमाणःशक्तिरंत्यंप्रगाथमालेभेसोर्धचतुर्केदग्ध

तंतंपुत्रोर्कंवसिष्ठःसमापयतेतिशाट्यायनकंवासिष्ठस्यैवहतपुत्रस्यार्षमितितांडकंभिस्यंवःष

कूनासंस्तवोवसिष्ठस्यसपुत्रस्येंद्रेणवासंवादःप्रभुक्रापंचाधिकावैश्वदेवंहाथा एका विंशतिर्द्वि

पदाअज्ञासहेरर्धचेउन्नरोहिबुध्न्यायशंनःपंचोनाशांलिः॥ ॥ॐ म॥युक्ष्वः।जज्ञो।वीर्याय।स्वधाः

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. वान् । चक्रिः । आपः । नर्यः । यत् । करिष्यन् । जग्मिः । युवा । नृऽसदनं । अवःऽभिः । त्राता । नः । इंद्रः । एनसः । मु
३० हः । चित् । हंता । वृत्रं । इंद्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारं । ऊती । कर्ता । सुऽदासे । अह । वै । ऊं इ
30 ति । लोकं । दाता । वसु । मुहुः । आ । दाशुषे । भूत् । युध्मः । अनर्वा । खजऽकृत् । समत्ऽवा । शूरः । सत्राषा
ट् । जनुषा । ईं । अषाळ्हः । वि । आसे । इंद्रः । पृतनाः । सुऽओजाः । अध । विश्वं । शत्रुऽयंतं । जघान । उभे इति ।
चित् । इंद्र । रोदसी इति । महिऽत्वा । आ । पप्राथ । तविषीभिः । तुविष्मः । नि । वज्रं । इंद्रः । हरिऽवान् । मिमिक्ष
न् । सं । अंधसा । मदेषु । वै । उवोच । वृषा । जजान । वृषणं । रणाय । तं । ऊं इति । चित् । नारी । नर्यं । ससूव ।
प्र । यः । सेनाऽनीः । अध । नृऽभ्यः । अस्ति । इनः । सत्वा । गोऽएषणः । सः । धृष्णुः । ३ । नु । चित् । सः । भ्रेषते । ३०

© Dharmartha Trust J&K. Digitized by eGangotri

जनः। न। आरेषत्। मनः। यः। अस्य। घोरं। आऽविवासात्। यज्ञैः। यः। इंद्रे। दधते। दुवः। सः। क्षयत्। सः। राये। ऋ
तऽपाः। ऋतेऽजाः। यत्। इंद्र। पूर्वः। अपराय। शिक्षन्। अयत्। ज्यायान्। कनीयसः। देष्णं। अमृतः। इत्।
परि। आसीत। दूरं। आ। चित्र। चित्र्यं। भर। रयिं। नः। यत्। ते। इंद्र। प्रियः। जनः। ददाशत्। असत्। निरेके।
अद्रिऽवः। सखा। ते। वयं। ते। अस्यां। सुऽमतौ। चनिष्ठाः। स्याम। वरूथे। अघ्नतः। नृऽपीतौ। एषः। स्तोमः।
अचिक्रदत्। वृषा। ते। उत। स्तामुः। मघऽवन्। अक्रपिष्ट। रायः। कामः। जरितारं। ते। आ। अगन्। त्वं। अंग।
शक्र। वस्वः। आ। शकः। नः। सः। नः। इंद्र। त्वऽयतायै। इषे। धाः। त्मना। च। ये। मघऽवानः। जुनंति। वस्वी। सु
ते। जरित्रे। अस्तु। शक्तिः। ६। २। असावि। देवं। गोऽऋजीकं। अंधः। नि। अस्मिन्। इंद्रः। जनुषा। ईं। उवोच।

पूयं०

© Dharmartha Trust J&K. Digitized by eGangotri

पु॰पं॰ बोधामसि। त्वा। हरिऽअश्व। यज्ञैः। बोध। नः। स्तोमं। अंधसः। मदेषु। प्र। यंति। यज्ञं। विपयंति। बर्हिः।
३३ सोमऽमादः। विदथे। दुध्रऽवाचः। नि। ऊं इति। भ्रियंते। यशसः। गृभात्। आ। दूरेऽउपब्दः। वृषणः। नृऽसा
31 चः। त्वं। इंद्र। स्रवितवै। अपः। करिति कः। परिऽस्थिताः। अहिना। शूर। पूर्वीः। त्वत्। वावक्रे। रथ्यः। न। धेनाः।
रेजंते। विश्वा। कृत्रिमाणि। भीषा। भीमः। विवेष। आयुधेभिः। एषां। अपांसि। विश्वा। नर्याणि। विद्वान्।
इंद्रः। पुरः। जर्हृषाणः। वि। दूधोत्। वि। वज्रऽहस्तः। महिना। जघान। न। यातवः। इंद्र। जूजुवुः। नः। न। वंदना।
शविष्ठ। वेद्याभिः। सः। शर्धत्। अर्यः। विषुणस्य। जंतोः। मा। शिश्नऽदेवाः। अपि। गुः। ऋतं। नः। ३। अभि। क्र
त्वा। इंद्र। भूः। अध। ज्मन्। न। ते। विव्यक्। महिमानं। रजांसि। स्वेन। हि। वृत्रं। शवसा। जघंथ। न। शत्रुः। ३३

© Dharmartha Trust J&K. Digitized by eGangotri

अंतः। विविदत्। सुधा। ते। देवाः। चित्। ते। असुर्यीय। पूर्वे। अनु। क्षत्राय। ममिरे। सहांसि। इंद्रः। मघानि। दयते।
विऽसह्य। इंद्रं। वाजस्य। जोहुवंत। सातौ। कीरिः। चित्। हि। त्वां। अवसे। जुहाव। ईशानं। इंद्र। सौभगस्य। भूरेः।
अवः। बभूथ। शतऽऊते। अस्मे इति। अभिऽक्षत्तुः। त्वाऽवतः। वरूता। सखायः। ते। इंद्र। विश्वहा। स्याम। न।
मः ऽवृधासः। महिना। तरुत्र। वन्वंतु। स्म। ते। अवसा। सं ऽईके। अभिऽइतिं। अर्यः। वनुषां। शवांसि। ६
। ४। पिब। सोमं। इंद्र। मंदतु। त्वा। यं। ते। सुषाव। हरिऽअश्व। अद्रिः। सोतुः। बाहुऽभ्यां। सुऽयतः। न। अर्वा।
यः। ते। मदः। युज्यः। चारुः। अस्ति। येन। वृत्राणि। हरिऽअश्व। हंसि। सः। त्वां। इंद्र। प्रभुवसो इति प्रभुऽवसो।
सो। ममत्तु। बोधा। सु। मे। मघऽवन्। वाचं। आ। इमां। यां। ते। वसिष्ठः। अर्चति। प्रऽशस्तिं। इमा। ब्रह्म। स
सेनइंद्रं ऋ॰ ५१

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ धऽमादे । जुषस्व । श्रुधि । हवं । विऽपिपानस्य । अद्रेः । बोध । विप्रस्य । अर्चतः । मनीषां । कृष्व । दुवांसि । अंतमा ।
३२ सचा । इमा । न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुऽस्तुतिं । असुर्यस्य । विद्वान् । सदा । ते । नाम । स्वऽयशः ।
32 विवक्मि ॥ ५ ॥ भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वां । इत् । मा । आरे । अस्मत् । मघऽवन् ।
ज्योक् । कः । करिति कः । तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यं । ब्रह्माणि । वर्द्धना । कृणोमि । त्वं । नृऽभिः । हव्यः ।
विश्वधा । असि । नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवंति । महिमानं । उग्र । न । वीर्यं । इंद्र । ते । न । रा
धः । ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इंद्र । ब्रह्माणि । जनयंत । विप्राः । अस्मे इति । ते । संतु । सख्या । शिवानि ।
यूयं॰ ॥ ९ ॥ उत् । ऊं इति । ब्रह्माणि । ऐरत । श्रवस्या । इंद्रं । सऽमर्ये । महय । वसिष्ठ । आ । यः । विश्वानि । शवसा । त ३२

© Dharmartha Trust J&K. Digitized by eGangotri

त्वा। न। उप। श्रोता। मे। ईवतः। वचांसि। अयामि। घोषः। इंद्र। देवऽजामिः। इरज्यंत। यत्। शुरुधः। विवाचि। न

हि। त्वं। आयुः। चिकिते। जनेषु। तानि। इत्। अंहांसि। अति। पर्षि। अस्मान्। युजे। रथं। गोऽएषणं। हरिऽभ्यां।

उप। ब्रह्माणि। जुजुषाणं। अस्थुः। वि। बाधिष्ट। स्यः। रोदसी इति। महिऽत्वा। इंद्रः। वृत्राणि। अप्रति। जघन्वा

न्। आपः। चित्। पिप्युः। स्तर्यः। न। गावः। नक्षन्। ऋतं। जरितारः। ते। इंद्र। याहि। वायुः। न। निऽयुतः। नः।

अच्छ। त्वं। हि। धीभिः। दयसे। वि। वाजान्। ते। त्वा। मदाः। इंद्र। मादयंतु। शुष्मिणं। तुविऽराधसं। जरित्रे।

एकः। देवऽत्रा। दयसे। हि। मर्तान्। अस्मिन्। शूर। सवने। मादयस्व। एव। इत्। इंद्रं। वृषणं। वज्रऽबाहुं।

वसिष्ठासः। अभि। अर्चंति। अर्कैः। गीं। गां। सदने। नरःऽभिः। पुरुऽहूत। मा। याहि। असः। यथा। नः। अविता।

सँनस्तुतो॰ अर्कैरितमा

मोनिशंद

© Dharmartha Trust J&K. Digitized by eGangotri

प० पं०
दधे। वाऽदेदः। वस्नानि। ममदः। च। सोमैः। गभीले। ते। मनः। इंद्र। द्विऽबर्हाः। सुतः। सोमः। परिऽसिक्ता। मधूनि।
३३ विसृष्टऽधेना। भरते। सुऽवृक्तिः। इयं। इंद्रं। जोहुवती। मनीषा। आ। नः। दिवः। आ। पृथिव्याः। ऋजीषिन्। इ
दं। बर्हिः। सोमऽपेयाय। याहि। वहंतु। त्वा। हरयः। मद्र्यंचं। आंगूषं। अछ। तवसं। मदाय। आ। नः। विश्वाभिः।
ऊतिऽभिः। सऽजोषाः। ब्रह्म। जुषाणः। हरिऽअश्व। याहि। वरीवृजत्। स्थविरेभिः। सुऽशिप्र। अस्मे इति। दध
त्। वृषणं। शुष्मं। इंद्र। एषः। स्तोमः। महे। उग्राय। वाहे। धुरिऽइव। अत्यः। न। वाजयन्। अधायि। इंद्र। त्वा।
अयं। अर्कः। ईट्टे। वस्वः। दिविऽइव। द्यां। अधि। नः। श्रोमतं। धाः। एव। नः। इंद्र। वार्यस्य। पूर्धि। प्र। ते। महीं।
सुऽमतिं। वेविदाम। इषं। पिन्व। मघवत्ऽभ्यः। सुऽवीरां। ६॥ ८॥ आ। ते। महः। इंद्र। ऊती। उग्र। सऽमन्यवः। य ३३
वः॥
यंयं०

© Dharmartha Trust J&K. Digitized by eGangotri

त्वा।सं ऽ अरंत।सेनाः।पताति।दिद्युत्।नर्यस्य।बाह्वोः।मा।ते।मनः।विष्वद्र्यक्।वि।चारीत्।मा।दुःऽगे।इंद्र।श्न
थिहि।अमित्रान्।अभि।ये।नः।मर्तासः।अमंति।आरे।तं।शंसं।कृणुहि।निनित्सोः।आ।नः।भर।संऽभ
रणं।वसूनां।शतं।ते।शिप्रिन्।ऊतयः।सुऽदासे।सहस्रं।शंसाः।उत।रातिः।अस्तु।जहि।वधः।वनुषः।म
र्त्यस्य।अस्मे इति।द्युम्नं।अधि।रत्नं।च।धेहि।त्वाऽवतः।हि।इंद्र।क्रत्वे।अस्मि।त्वाऽवतः।अवितुः।शूर।रा
तौ।विश्वा।इत्।अहा।नि।तविषीऽवः।उग्र।ओकः।कृणुष्व।हरिऽवः।न।मर्धीः।कुत्साः।एते।हरिऽअश्वा
य।शूषं।इंद्रे।सहः।देवऽजूतं।इयानाः।सत्रा।कृधि।सुऽहना।शूर।वृत्रा।वयं।तरुत्राः।सनुयाम।वाजं।
ं॥न।सोमः।इंद्रं।असुतः।ममाद।न।अब्रह्माणः।मघऽवानं।सुतासः।तस्मै।उक्थं।जनये।यत्।जु

हं आनंद०

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. जोषत्। नरः। वत्। नवीयः। भ्रणवत्। यथा। नः। उक्थेऽउक्थे। सोमः। इंद्रं। ममाद। नीथेऽनीथे। मघऽवानं। सु
।।३४।। तासः। यत्। ईं। सऽबाधः। पितरं। न। पुत्राः। समानऽदक्षाः। अवसे। हवंते। चकार। ता। कृणवत्। नूनं। अ
न्या। यानि। ब्रुवंति। वेधः। सुऽतेषु। जनीःऽइव। पतिः। एकः। समानः। नि। मामृजे। पुरः। इंद्रः। सु। सर्वाः। ए
34 व। ईं। आहुः। उत। शृण्वे। इंद्रः। एकः। विऽभक्ता। तरणिः। मघानां। मिथःऽतुरः। ऊतयः। यस्य। पूर्वीः। अस्मे
इति। भद्राणि। सश्चत। प्रियाणि। एव। वसिष्ठः। इंद्रं। ऊतये। नृणां। कृष्टीनां। वृषभं। सुते। गृणाति। सह
स्रिणः। उप। नः। मा। हि। वाजान्। ९। इंद्रं। नरः। नेमऽधिता। हवंते। यत्। पार्याः। युनजते। धियः। ताः।
शूरः। नृऽसाता। शवसः। चकानः। आ। गोऽमति। व्रजे। भज। त्वं। नः। यः। इंद्र। शुष्मः। मघऽवन्। नो। अ ।।३५।।

धूँयं

© Dharmartha Trust J&K. Digitized by eGangotri

स्त्व।शिक्ष।सखिऽभ्यः।पुरुऽहूत।नृऽभ्यः।त्वं।हि।दृळ्हा।मघऽवन्।विऽचेताः।अप।वृधि।परिऽवृतं।न।रा
धः।इंद्रः।राजा।जगतः।चर्षणीनां।अधि।क्षमि।विषुऽरूपं।यत्।अस्ति।ततः।ददाति।दाशुषे।वसूनि।चो
दत्।राधः।उपऽस्तुतः।चित्।अर्वाक्।नु।चित्।नः।इंद्रः।मघऽवा।सऽहूती।दानः।वाजं।नि।यमते।नः।ऊ
ती।अनूना।यस्य।दक्षिणा।पीपाय।वामं।नृऽभ्यः।अभिऽवीता।सखिऽभ्यः।नु।इंद्र।राये।वरिवः।कृ
धि।नः।आ।ते।मनः।ववृत्याम।म।मघाय।गोऽमत्।अश्वऽवत्।रथऽवत्।व्यंतः।०॥२१॥ब्रह्म।नः।इंद्र। पू॰यं॰
उप।याहि।विद्वान्।अर्वांचः।ते।हरयः।संतु।युक्ताः।विश्वे।चित्।हि।त्वा।विऽहवंत।मर्ताः।अस्माकं।इ
त्।शृणुहि।विश्वंऽइन्व।हवं।ते।इंद्र।महिमा।वि।आनट्।ब्रह्म।यत्।पासि।शवसिन्।ऋषीणां।आ

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. यत्र। वज्रं। आ। दधिषे। हस्ते। उग्र। घोरः। सन्। क्रत्वा। अजनिष्ठाः। अषाढः। तव। प्रऽनीती। इन्द्र। जोहुवानान्।
॥३५॥ सं। यत्र। नॄन्। न। रोदसी इति। निनेथ। मह। क्षत्राय। शवसे। हि। जज्ञे। अतूर्तुं। चित्। त्वा। अतूर्तुं। अभि
35 स्मन्। आ। एभिः। नुः। इन्द्र। अहऽभिः। दशस्य। दुःऽमित्रासः। हि। क्षितयः। पवन्ते। प्रति। यत्। पश्य। अनृतं। अ
नेनाः। अव। द्विता। वरुणः। मायी। नः। सात्। त्वो चे मा। इन्द्र। मघऽवा। नः। एनां। महः। रायः। राधसः। यत्।
अ ददत्। नः। यः। अर्चतः। ब्रह्मऽकृतिं। [illegible]। अयं। सोमः। इन्द्र। तुभ्यं। सुन्वे। आ। तु। प्र। याहि। हरिऽवः।
तत्ऽओकाः। पिब। तु। अस्य। सुऽसुतस्य। चारोः। ददः। मघानि। मघऽवन्। इयानः। ब्रह्मन्। वीर। ब्रह्मऽकृ
तिं। जुषाणः। अर्वाचीनः। हरिऽभिः। याहि। तूयं। अस्मिन्। ऊं इति। सु। सवने। मादयस्व। उप। ब्रह्माणि। ॥३६॥

यूंथं०

© Dharmartha Trust J&K. Digitized by eGangotri

भ्रणवः। इमा। नः। का। ते। अस्ति। अरंऽकृतिः। सुऽवृक्तैः॥ कदा। नूनं। ते। मघऽवन्। दाशेम। विश्वाः। मतीः। आ।
ततने। त्वाऽया। अध। मे। इंद्र। भ्रणवः। हवा। इमा। उतो इति। घा। ते। पुरुऽत्याः। इत। आसन्। येषां। पूर्वेषां। अ
भ्रणोः। ऋषीणां। अध। अहं। त्वा। मघऽवन्। जोहवीमि। त्वं। नः। इंद्र। असि। प्रऽमतिः। पिताऽइव॥ ३३॥ घोचेमेदिधं० रु०१
आ। नः। देव। शवसा। याहि। शुष्मिन्। भव। वृधः। इंद्र। रायः। अस्य। महे। नृम्णाय। नृऽपते। सुऽवज्र।
महि। क्षत्राय। पौंस्याय। शूर॥ हवंते। ऊं इति। त्वा। हव्याः। वि। वाचि। तनूषु। शूराः। सूर्यस्य। सातौ। त्वं। वि
श्वेषु। सेन्यः। जनेषु। त्वं। वृत्राणि। रंधय। सुऽहंतु। अहा। यत्। इंद्र। सुऽदिना। विऽउच्छान्। दधः। यत्। के
सीदता तुं। उप। मां। समतः। सु। नि। अग्निः। असुरः। ना। होता। हुवानः। अत्र। सुऽभगाय। देवान्। वयं। नेता। इंद्राय।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. च। देव। स्तवंत। शूर। ददतः। मघानि। यच्छ। सूरिऽभ्यः। उपऽमं। वरूथं। सुऽआभुवः। जरणां। अश्नवंत। ० वो चेमर्दिद्धं
३६ ।१४॥ प्र। वः। इंद्राय। मादनं। हरिऽअश्वाय। गायत। सखायः। सोमऽपाव्ने। शंस। इत्। उक्थं। सुऽदा
नवे। उत। द्युक्षं। यथा। नरः। चकृम। सत्यऽराधसे। त्वं। नः। इंद्र। वाजऽयुः। त्वं। गव्युः। शतक्रतो इति शत
वयमिंद्र त्वायवो ऽक्रतो। त्वं। हिरण्यऽयुः। वसो इति। अभि। प्र। नोनुमः। वृषन्। विद्धि। तु। अस्य। नः। वसो इति। मा।
36 नः। निदे। च। वक्तवे। अर्यः। रंधीः। अराव्णे। त्वे इति। अपि। क्रतुः। मम। त्वं। वर्म। असि। सऽप्रथः।
पुरःऽयोधः। च। वृत्रऽहन्। त्वया। प्रति। ब्रुवे। युजा॥१५॥ महान्। उत। असि। यस्य। ते। अनु। स्वधा
वरी इति स्वधाऽवरी। सहः। मम्नाते इति। इंद्र। रोदसी इति। तं। त्वा। मरुत्वती। परि। भुवत्। वा ३६

© Dharmartha Trust J&K. Digitized by eGangotri

प्रवोमहे

णी। सऽयावरी। नक्षमाणा। सहऽयुग्भिः। ऊर्ध्वासः। त्वा। अनु। इंदवः। भुवन्। दस्मं। उप। द्यवि। सं। ते। नमंत।
कृष्टयः॥०॥ महिऽवृधे। भरध्वं। प्रऽचेतसे। प्र। सुऽमतिं। कृणुध्वं। विशः। पूर्वीः। प्र। चर। चर्षणिऽप्राः॥ उरु
ऽव्यचसे। महिने। सुऽवृक्तिं। इंद्राय। ब्रह्म। जनयंत। विप्राः। तस्य। व्रतानि। न। मिनंति। धीराः॥ इंद्रं। वाणीः
। अनुत्तऽमन्युं। एव। सत्रा। राजानं। दधिरे। सहध्यै। हरिऽश्वाय। बर्हय। सं। आपीन्॥१६॥ मो इति।
सु। त्वा। वाघतः। चन। आरे। अस्मत्। नि। रीरमन्। आरात्तात्। चित्। सऽधमादं। नः। आ। गहि। इह।
वा। सन्। उप। श्रुधि। इमा। हि। ते। ब्रह्मऽकृतः। सुते। सचा। मधौ। न। मक्षः। आसते। इंद्रे। कामं। जरिता
रः। वसुऽयवः। रथे। न। पादं। आ। दधुः। रायःऽकामः। वज्रऽहस्तं। सुऽदक्षिणं। पुत्रः। न। पितरं। हुवे। इ

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं.
३७
37

मो। इंद्राय। सुन्विरे। सोमासः। दधिऽआशिरः। तान्। आ। मदाय। वज्रऽहस्त। पीतये। हरिऽभ्यां। याहि।
ओकः। आ। श्रवत्। श्रुतऽकर्णः। ईयते। वसूनां। नु। चित्। नः। मर्धिषत्। गिरः। सद्यः। चित्। यः। सहस्रा
णि। शता। ददत्। नकिः। दित्सन्तं। आ। मिनत्। ३ ॥ सः। वीरः। अप्रतिऽस्कुतः। इंद्रेण। शूशुवे। नृऽभिः।
यः। ते। गभीरा। सवना। नि। वृत्रऽहन्। सुनोति। आ। च। धावति। भव। वरूथं। मघऽवन्। मघोनां।
यत्। सं। अजासि। शर्धतः। नि। त्वाऽहतस्य। वेदनं। भक्षेमहि। आ। दुःऽनशः। भर। गयं। सुनोत। सो
मऽपाव्ने। सोमं। इंद्राय। वज्रिणे। पचत। पक्तीः। अवसे। कृणुध्वं। इत्। पृणन्। इत्। पृणते। मयः। मा।
त्रेधत। सोमिनः। दक्षत। महे। कृणुध्वं। राये। आऽतुजे। तरणिः। इत्। जयति। क्षेति। पुष्यति। न। देवा ३८

© Dharmartha Trust J&K. Digitized by eGangotri

अस्मांकंबोध्यविता

सः।कृऽवत्।नये।नकिः।सुऽदासः।रथं।परि।आस्त।न।रीरमत्।इंद्रः।यस्य।आ।अविता।यस्य।मरुतः।गम
त्।सः।गोऽमति।व्रजे।।३।।गमत्।वाजं।वाजयन्।इंद्र।मर्त्यः।यस्य।त्वं।अविता।भुवः।०रथानां।अ
स्माकं।शूर।नृणां।उत्।इत्।नु।अस्य।रिच्यते।अंशः।धनं।न।जिग्युषः।यः।इंद्रः।हरिऽवान्।न।दभं
ति।तं।रिपः।दक्षं।दधाति।सोमिनि।मंत्रं।अखर्वं।सुऽधितं।सुऽपेशसं।दधात।यज्ञियेषु।आ।पूर्वीः।
चन।प्रऽसितयः।तरंति।तं।यः।इंद्रे।कर्मणा।भुवत्।कः।तं।इंद्र।त्वाऽवसुं।आ।मर्त्यः।दधर्षति।श्रद्धा।इ
त्।ते।मघऽवन्।पार्ये।दिवि।वाजी।वाजं।सिसासति।मघोनः।स्म।वृत्रऽहत्येषु।चोदय।ये।ददति।
प्रिया।वसु।तव।प्रऽनीती।हरिऽअश्व।सूरिऽभिः।विश्वा।तरेम।दुःऽइता।।५।।तव।इत्।इंद्र।अवमं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. वसु।त्वं।पुष्यसि।मध्यमं।सत्रा॥विश्वस्य।परमस्य।राजसि।नकिः।त्वा।गोषु।वृण्वते।त्वं।विश्वस्य।धन
३८ दाः।आसि।श्रुतः।ये।ईं।भवंति।आजयः।तव।अयं।विश्वः।पुरुऽहूत।पार्थिवः।अवस्युः।नाम।भिक्षते।य
त्।इंद्र।यावतः।त्वं।एतावत्।अहं।ईशीय।स्तोतारं।इत्।दिधिषेय।रदद्वसो इति रदत्ऽवसो।न।पापऽत्वा
38 य।रासीय।शिक्षेयं।इत्।महऽयते।दिवेऽदिवे।रायः।आ।कुहचित्ऽविदे।नहि।त्वत्।अन्यत्।मघऽवन्
।नः।आप्यं।वस्यः।अस्ति।पिता।चन।तरणिः।इत्।सिसासति।वाजं।पुरंऽध्या।युजा।आ।वः।इंद्रं।पु
रुऽहूतं।नमे।गिरा।नेमिं।तष्टाऽइव।सुऽद्र्वं।न।दुःऽस्तुती।मर्त्यः।विंदते।वसु।न।स्रेधंतं।रयिः।न
शत्।सुऽशक्तिः।इत्।मघऽवन्।तुभ्यं।माऽवते।देष्णं।यत्।पार्ये।दिवि।अभि।त्वा।शूर।नोनुमः।अदु ३८

© Dharmartha Trust J&K. Digitized by eGangotri

अस्माकंबोध्यविता महाधने

ग्धाःऽइव।धेनवः।ईशानं।अस्य।जगतः।स्वःऽदृशं।ईशानं।इंद्र।तस्थुषः।न।त्वाऽवान्।अन्यः।दिव्यः।न।
पार्थिवः।न।जातः।न।जनिष्यते।अश्वऽयंतः।मघऽवन्।इंद्र।वाजिनः।गव्यंतः।त्वा।हवामहे।अभि।सतः।
तत्।आ।भर।इंद्र।ज्यायः।कनीयसः।पुरुऽवसुः।हि।मघऽवन्।सनात्।असि।भरेऽभरे।च।हव्यः।परा।
नुदस्व।मघऽवन्।अमित्रान्।सुऽवेदाः।नः।वसु।कृधि।भव।वृधः।सखीनां।इंद्र।क्रतुं।नः।आ।भर।
पिता।पुत्रेभ्यः।यथा।शिक्ष।नः।अस्मिन्।पुरुऽहूत।यामनि।जीवाः।ज्योतिः।अशीमहि।मा।नः।अ
ज्ञाताः।वृजनाः।दुःऽआध्यः।मा।अशिवासः।अव।क्रमुः।त्वया।वयं।प्रऽवतः।शश्वतीः।अपः।अति।
शूर।तरामसि।२३॥श्वित्यंचः।मा।दक्षिणतःऽकपर्दाः।धियंऽजिन्वासः।अभि।हि।प्रऽमंदुः।उत्ऽ

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. तिष्ठन्।वो।चे।परि।बर्हिषः।नॄन्।न।मे।दूरात्।अवितवे।वसिष्ठाः॥दूरात्।इंद्रं।अनयन्।आ।सुतेन।ति
३९ रः।वैशंतं।अति।पातं।उग्रं।पाशऽद्युम्नस्य।वायतस्य।सोमात्।सुतात्।इंद्रः।अवृणीत।वसिष्ठान्।एव।
हवैन्तुकं इत्।नु।कं।सिंधुं।एभिः।ततार।०भेदं।एभिः।जघान।०दाशऽराज्ञे।सुऽदासं।प्र।आवत्।इंद्रः।ब्रह्मणा।वः।
39 वसिष्ठाः।जुष्टी।नरः।ब्रह्मणा।वः।पितॄणां।अक्षं।अव्ययं।न।किल।रिषाथ।यत्।शक्वरीषु।बृहता।
रवेण।इंद्रे।शुष्मं।अदधात।वसिष्ठाः।उत्।द्यांऽइव।इत्।तृष्णऽजः।नाथितासः।अदीधयुः।दाशऽरा
ज्ञे।वृतासः।वसिष्ठस्य।स्तुवतः।इंद्रः।अश्रोत्।उरुं।तृत्सुऽभ्यः।अकृणोत्।ऊं इति।लोकं।२।दंडाःऽ
इवाऽइत्।गोऽअजनासः।आसन्।परिऽछिन्नाः।भरताः।अर्भकासः।अभवत्।च।पुरःऽएता।वसि ३९

© Dharmartha Trust J&K. Digitized by eGangotri

च्छिन्नः । आत् । इत् । तृत्सूनां । विशः । अप्रथंत । त्रयः । कृण्वंति । भुवनेषु । रेतः । तिस्रः । प्रऽजाः । आर्याः । ज्योतिःऽ
अग्राः । त्रयः । घर्मासः । उषसं । सचंते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः । सूर्यस्यऽइव । वक्षथः ।
ज्योतिः । एषां । समुद्रस्यऽइव । महिमा । गभीरः । वातस्यऽइव । प्रऽजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अ
नुऽएतवे । वः । ते । इत् । निण्यं । हृदयस्य । प्रऽकेतैः । सहस्रऽवल्शं । अभि । सं । चरंति । यमेन । ततं । परिऽधिं ।
वयंतः । अप्सरसः । उप । सेदुः । वसिष्ठाः । विऽद्युतः । ज्योतिः । परि । संऽजिहानं । मित्रावरुणा । यत् । अपश्य
तां । त्वा । तत् । ते । जन्म । उत । एकं । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥ २३ ॥ उत । असि । मै
त्रावरुणः । वसिष्ठ । उर्वश्याः । ब्रह्मन् । मनसः । अधि । जातः । द्रप्सं । स्कन्नं । ब्रह्मणा । दैव्येन । विश्वे । देवाः ।

© Dharmartha Trust J&K. Digitized by eGangotri

पु.पं. पुष्करे। त्वा। अददंत। सः। प्रऽकेतः। उभयस्य। प्रऽविद्वान्। सहस्रऽदानः। उत। वा। सऽदानः। ०ं वयिष्यन्।
५० अप्सरसः। परि। जज्ञे। वसिष्ठः। सत्रे। ह। जातौ। इषिता। नमःऽभिः। कुंभे। रेतः। सिसिचतुः। समानं।
ततः। ह। मानः। उत्। इयाय। मध्यात्। ततः। जातं। ऋषिं। आहुः। वसिष्ठं। उक्थऽभृतं। सामऽभृतं। बिभ
50 र्ति। ग्रावाणं। बिभ्रत्। प्र। वदाति। अग्रे। उप। एनं। आ। ध्वं। सुऽमनस्यमानाः। आ। वः। गच्छाति। प्रऽतृदः।
वसिष्ठः॥ २४॥ अनुवाकः॥ ३॥ प्र। शुक्रा। एतु। देवी। मनीषा। अस्मत्। सुऽतष्टः। रथः। न। वाजी। विदुः। पृ
थिव्याः। दिवः। जनित्रं। शृण्वंति। आपः। अध। क्षरंतीः। आपः। चित्। अस्मै। पिन्वंत। पृथ्वीः। वृत्रेषु। शू
राः। मंसंत। उग्राः। आ। धूःऽसु। अस्मै। दधात। अश्वान्। इंद्रः। न। वज्री। हिरण्यऽबाहुः। अभि। प्र। स्थात। ५०

© Dharmartha Trust J&K. Digitized by eGangotri

ता। अहःऽइ्वाय। यज्ञं। पान्तोः। ऽइ्वाय। त्मना। त्मना। हिनोत। त्मना। समत्ऽसु। हिनोत। यज्ञं। दधात। केतुं। जना
य। वीरं। उत्। अस्य। शुष्मात्। भानुः। न। आर्त। बिभर्ति। भारं। पृथिवी। न। भूम। ह्वयामि। देवान्। अया
तुः। अग्ने। साधन्। ऋतेन। धियं। दधामि। अभि। वः। देवीं। धियं। दधिध्वं। प्र। वः। देवऽत्रा। वाचं। कृणुध्वं।
आ। चष्टे। आसां। पाथः। नदीनां। वरुणः। उग्रः। सहस्रऽचक्षाः॥ २५॥ राजा। राष्ट्रानां। पेशः। नदीनां।
अनुत्तं। अस्मै। क्षत्रं। विश्वऽआयु। अविष्टो इति। अस्मान्। विश्वासु। विक्षु। अद्युं। कृणोत। शंसं। नि
निसोः। वि। एतु। दिद्युत्। द्विषां। अशेवा। युयोत। विष्वक्। रपः। तनूनां। अवीत्। नः। अग्निः। हव्यऽअ
त्। नमःऽभिः। प्रेष्ठः। अस्मै। अधायि। स्तोमः। सऽजूः। देवेभिः। अपां। नपातं। सखायं। कृध्वं। शिवः।

© Dharmartha Trust J&K. Digitized by eGangotri

मा नो हिर्बुध्न्यो रिषेधात्

प.पं. नः। अस्तु। अप्ऽजां। उक्थैः। अहिं। गृणीषे। बुध्ने। नदीनां। रजःऽसु। सीदन्। ँ मा। यज्ञः। अस्य। स्रिधत्।

५१ ऋतऽयोः। उत। नः। एषु। नृषु। श्रवः। धुः। प्र। राये। यंतु। शर्धंतः। अर्यः। तपंति। शत्रुं। स्वः। न। भूम। महाऽसे

41 नासः। अमेभिः। एषां। आ। यत्। नः। पत्नीः। गमंति। अच्छ। त्वष्टा। सुऽपाणिः। दधातु। वीरान्। ॥ रध। प्रति।

नः। स्तोमं। त्वष्टा। जुषेत। स्यात्। अस्मे इति। अरमतिः। वसुऽयुः। ता। नः। रासन्। रातिऽसाचः। वसूनि।

आरोदँसीवरुणा नीश्रृणोतु॥ ँ वरूत्रीभिः। सुऽशरणः। नः। अस्तु। त्वष्टा। सुऽदत्रः। वि। दधातु। रायः। तत्। नः। रायः। पर्वताः। तत्।

नः। आपः। तत्। रातिऽसाचः। ओषधीः। उत। द्यौः। वनस्पतिऽभिः। पृथिवी। सऽजोषाः। उभे इति। रोदसी

इति। परि। पासतः। नः। अनु। तत्। उर्वी इति। रोदसी इति। जिहातां। अनु। द्युक्षः। वरुणः। इंद्रऽसखा। ५१

© Dharmartha Trust J&K. Digitized by eGangotri

अनु। विश्वौ। मरुतः। यो। सहासः। रायः। स्याम। धरुणं। धियध्यै। तत्। नः। इंद्रः। वरुणः। मित्रः। अग्निः।
आपः। ओषधीः। वनिनः। जुषंत। शर्मन्। स्याम। मरुतां। उपऽस्थे॥ २॥ शं। नः। इंद्राग्नी इति। भव
तां। अवःऽभिः। शं। नः। इंद्रावरुणा। रातऽहव्या। शं। इंद्रासोमा। सुविताय। शं। योः। शं। नः। इंद्रापूषणा।
वाजऽसातौ। शं। नः। भगः। शं। ऊं इति। नः। शंसः। अस्तु। शं। नः। पुरंऽधिः। शं। ऊं इति। संतु। रायः। शं। नः।
सत्यस्य। सुऽयमस्य। शंसः। शं। नः। अर्यमा। पुरुऽजातः। अस्तु। शं। नः। धाता। शं। ऊं इति। धर्ता। नः।
अस्तु। शं। नः। उरूची। भवतु। स्वधाभिः। शं। रोदसी इति। बृहती इति। शं। नः। अद्रिः। शं। नः। देवानां। सु
ऽहवानि। संतु। शं। नः। अग्निः। ज्योतिःऽअनीकः। अस्तु। शं। नः। मित्रावरुणौ। अश्विना। शं। शं। नः।

© Dharmartha Trust J&K. Digitized by eGangotri

वी

प.पं. सुऽकृतां । सुऽकृतानि । संतु । शं । नः । इषिरः । अभि । वातु । वातः । शं । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शं ।

५२ अंतरिक्षं । दृशये । नः । अस्तु । शं । नः । ओषधीः । वनिनः । भवंतु । शं । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥ ४

॥ शं । नः । इंद्रः । वसुऽभिः । देवः । अस्तु । शं । आदित्येभिः । वरुणः । सुऽशंसः । शं । नः । रुद्रः । रुद्रेभिः । जलाषः ।

42 शं । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु । शं । नः । सोमः । भवतु । ब्रह्म । शं । नः । शं । नः । ग्रावाणः । शं । ऊं इति । सं

तु । यज्ञाः । शं । नः । स्वरूणां । मितयः । भवंतु । शं । नः । प्रऽस्वः । शं । ऊं इति । अस्तु । वेदिः । शं । नः । सूर्यः । उरुऽच

क्षाः । उत् । एतु । शं । नः । चतस्रः । प्रऽदिशः । भवंतु । शं । नः । पर्वताः । ध्रुवयः । भवंतु । शं । नः । सिंधवः । शं । ऊं इ

ति । संतु । आपः । शं । नः । अदितिः । भवतु । व्रतेभिः । शं । नः । भवंतु । मरुतः । सुऽअर्काः । शं । नः । विष्णुः । शं । ५२

© Dharmartha Trust J&K. Digitized by eGangotri

शंनःसत्यस्य

ऊं इति। पूषा। नः। अस्तु। शं। नः। भवित्रं। शं। ऊं इति। अस्तु। वायुः। शं। नः। देवः। सविता। त्रायमाणः। शं। नः।
भवंतु। उषसः। विऽभातीः। शं। नः। पर्जन्यः। भवतु। प्रऽजाभ्यः। शं। नः। क्षेत्रस्य। पतिः। अस्तु। शंऽभुः॥१०
॥ शं। नः। देवाः। विश्वऽदेवाः। भवंतु। शं। सरस्वती। सह। धीभिः। अस्तु। शं। अभिऽसाचः। शं। ऊं इति। रा
तिऽसाचः। शं। नः। दिव्याः। पार्थिवाः। शं। नः। अप्याः। पतयः। भवंतु। शं। नः। अर्वंतः। शं। ऊं इति। संतु।
गावः। शं। नः। ऋभवः। सुऽकृतः। सुऽहस्ताः। शं। नः। भवंतु। पितरः। हवेषु। शं। नः। अजः। एकऽपात्। दे
वः। अस्तु। शं। नः। अहिः। बुध्न्यः। शं। समुद्रः। शं। नः। अपां। नपात्। पेरुः। अस्तु। शं। नः। पृश्निः। भव
तु। देवऽगोपा। जुषंत। इदं। ब्रह्म। क्रियमाणं। नवीयः। शृण्वंतु। नः। दिव्याः। पार्थिवासः। गोऽजाताः।

आदित्या रुद्रा वसवो

© Dharmartha Trust J&K. Digitized by eGangotri

बृ.कं.

१.५. उत। यो। यज्ञियासः। यो। देवानां। यज्ञियाः। यज्ञियानां। मनोः। यजत्राः। अमर्ताः। ऋतऽज्ञाः। ते। नः। रा
४३ संतां। उरुऽगायं। अद्य। उणः। इति पंचमाष्टके त्रयोध्यायः॥ ॥ॐ नमः॥ ॥प्रश्नसनवाको शो बुद्ध्यः
सावित्रमस्य वाजिन्यो भगमिति मागोवाइंद्रं उध्वः स्वस्ति वैश्वदेवं त्वा आप्तिः त्रातं भगां जगत्याद्यालिं
43 गोक्त देवतां स्यो पस्या प्रश्नस्ताणः पैडं वैश्वदेवं तु प्रवः पंच दधिक्रां दाधिक्रं जगत्याद्यालिंगोक्त देवतां द
वश्चतुष्कं सावित्रमिमा रोद्रं त्रिष्टुबंतमा पोयमा पंसम मुक्षण आभर्वमं स्या वैश्वदेवी वा समुद्रज्ये
ष्ठा आपमामां मैत्रावरुण्या आग्नेयी वैश्वदेवी नदी स्तुतिर्जागतमं स्यात्रि जगती शक्करी वा दित्यानां
त्वमादित्यं त्वादि स्या सः प्रद्यावा द्यावा पृथिवी यं चास्तो वा स्तोष्पत्यं ममी वहा ष्टौ चास्तोष्पत्या ४३

© Dharmartha Trust J&K. Digitized by eGangotri

घागायत्री शेषास्त्वुपरिष्टाद्बृहत्यादयोनुष्टुभः प्रस्तावि न्यउपनिषत्कं ईपं चाधिका मारुतं ह्यायाए

कादशाद्विपदामध्वः सप्तप्रसामुक्षेषट् यंत्राय ध्वे द्वादशान्नि प्रगाथादि नवम्याद्यागायत्र्यौसानुष्टुप्

रोद्रीमरुत्सुविमोचनी॥ ॐ म॥ ग्रा॥ बस्ता॥ ए तु॥ सदनात॥ ऋतस्य॥ वि॥ रश्मिऽभिः॥ ससृजे॥ सूर्यैः॥ गाः॥ वि

सानु॥ पृथिवी॥ सस्तो॥ उर्वी॥ पृथु॥ प्रतीकं॥ अधि॥ आ॥ ईधे॥ अग्निः॥ इमां॥ वां॥ मित्रावरुणा॥ सुऽशक्तिं॥

इषं॥ न॥ कृण्वे॥ असुरा॥ नवीयः॥ इनः॥ वां॥ अन्यः॥ पुरुऽवीः॥ अदब्धः॥ जनो॥ च॥ मित्रः॥ यतति॥ ब्रुवाणः॥ आ

वातस्य॥ ध्रजतः॥ रंते॥ इत्याः॥ अपीपयंत॥ धेनवः॥ न॥ सूदाः॥ महः॥ दिवः॥ सदने॥ जायमानः॥ अचिक्रदत्॥ वृ

षभः॥ सस्मिन्॥ ऊधन्॥ गिरा॥ यः॥ एता॥ युनजत्॥ हरी इति॥ ता॥ इंद्र॥ प्रिया॥ सुऽरथा॥ शूर॥ धायू इति॥ प्र॥ यः॥ म

ना

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ न्युं।रिरिक्षन्तः।मिनाति।आ।सुऽक्रतुं।अर्यमणं।ववृत्यां।यजंते।अस्य।सख्यं।वयः।च।नमस्विनः।स्वे
४४ ।ऋतस्य।धामन्।वि।पृक्षः।बाबधे।नृऽभिः।स्तवानः।इदं।नमः।रुद्राय।प्रेष्ठं॥५॥आ।यत्।साकं।य
शसः।वावशानाः।सरस्वती।सप्तथी।सिंधुऽमाता।याः।सुस्वयंत।सुऽदुघाः।सुऽधाराः।अभि।स्वे
न।पयसा।पीप्यानाः।उत।त्ये।नः।मरुतः।मंदसानाः।धियं।तोकं।च।वाजिनः।अवंतु।मा।नः।परि
ख्यत्।अक्षरा।चरंती।अवीवृधन्।युज्यं।ते।रयिं।नः।प्र।वः।महीं।अरमतिं।कृणुध्वं।प्र।पूषणं।वि
दथ्यं।न।वीरं।भगं।धियः।अवितारं।नः।अस्याः।सातौ।वाजं।रातिऽसाचं।पुरंऽधिं।अच्छ।अयं।वः
।मरुतः।श्लोकः।एतु।अच्छ।विष्णुं।निसिक्तऽपां।अवःऽभिः।उत।प्रऽजायै।गृणते।वयः।धुः।९।रा।आ। ४४

यूयं॰

© Dharmartha Trust J&K. Digitized by eGangotri

वः। वाहिष्ठः। वहतु। स्तवध्यै। रथः। आ। वाजाः। ऋभुक्षणः। अमृक्तः। अभि। त्रिऽपृष्ठैः। सवनेषु। सोमैः। मदे। सुऽशिप्राः

महःऽभिः। पृणध्वं। यूयं। हि। अस्मे। मघवत्ऽसु। धत्थ। स्वःऽदृशः। ऋभुक्षणः। अमृक्तं। सं। यज्ञेषु। स्वधाऽवंतः

पिबध्वं। वि। नः। राधांसि। मतिऽभिः। दयध्वं। उत। वोचिथ। हि। मघऽवन्। देष्णं। महः। अर्भस्य। वसुनः। विऽभा

गं। उभा। ते। पूर्णा। वसुना। गभस्ती इति। न। सूनृता। नि। यमते। वसव्या। त्वं। इंद्र। स्वऽयशाः। ऋभुक्षाः। वा

जः। न। साधुः। अस्तं। एषि। ऋक्वा। वयं। नु। ते। दाश्वांसः। स्याम। ब्रह्म। कृण्वंतः। हरिऽवः। वसिष्ठाः। सनिता

असि। प्रऽवतः। दाशुषे। चित्। याभिः। विवेषः। हरिऽअश्व। धीभिः। ववन्म। नु। ते। युज्याभिः। ऊती। कदा। नः

इंद्र। रायः। आ। दशस्येः॥ ३॥ वासयसिऽइव। वेधसः। त्वं। नः। कदा। नः। इंद्र। वचसः। बुबोधः। अस्तं। तात्या।

© Dharmartha Trust J&K. Digitized by eGangotri

हिरण्ययीममतिंयामशिश्रेत् ८

१.१. धियाारयिंासुऽवीरंाप्रसःानःाअर्वााानिाजुहीताावाजीाअभिायंादेवीाानिःऽऋतिःाचित्ऌाईशोनक्षतो
४५ इन्द्रंाशरदःासुऽप्रक्षःागुपााञ्रिःऽबंधुःाजरतःऽअंहिंाएतिाअस्वऽवेशंायंाकृणवंताामर्तःाआानुःाराधां
सिासवितुःारितिास्तुवध्यैाआारायःायंतुापर्वतस्याारातौासदाानुःादिव्यःापायुःासिसक्तुाःाा यूयं
उदु ष्य देवः स विता ःपत्याामाःानूनंाभगःाहव्यःामाातुषेभिःाविायःारत्नााापुरुःऽवसुःादधाातिाउताऊंइतिातिष्ठासवित
रितिाश्रुधिाअस्यााहिरण्यऽपाणोप्रऽभृतौाऋतस्याावि उवींपृथ्वींाअमतिंासृजानःाआानृऽ
45 भ्यःामर्तऽभोजनंासुवानःाअपिास्तुतःासविताादेवःाअस्तुायंाआाचित्राविश्वाेवसवःागृणंतिा
सःानःास्तोमानाानमस्यःाचनःाधात्राविश्वेभिःापातुापायुऽभिःानिासूरीनाा अदितिःागृणातिा ४५

अभियं देवी

© Dharmartha Trust J&K. Digitized by eGangotri

सुवे। देवस्य। सवितुः। जुषाणा। अभि। सं॒ऽराजः। वरुणः। गृणंति। अभि। मित्रासः। अर्यमा। सऽजोषाः। अ
भि। याः। मिथः। वनुषः। सपंते। रातिं। दिवः। रातिऽसाचः। पृथिव्याः। अहिः। बुध्न्यः। उत। नः। शृणोतु। वरू
त्री। एकधेनुऽभिः। नि। पातु। अनु। तत्। नः। जाःऽपतिः। मंसीष्ट। रत्नं। देवस्य। सवितुः। इयानः। भगं। उ
वी ग्रः। अवसे। जोहैति। भगं। अनुग्रः। अध। याति। रत्नं। शं। नः। भवंतु। वाजिनः। हवेषु। देवऽताता। मितऽ
द्रवः। सुऽअर्काः। जंभयंतः। अहिं। वृकं। रक्षांसि। सनेमि। अस्मत्। युयवन्। अमीवाः। वाजेऽवाजे।
अवत। वाजिनः। नः। धनेषु। विप्राः। अमृताः। ऋतऽज्ञाः। अस्य। मध्वः। पिबत। मादयध्वं। तृप्ताः। या
त। पथिऽभिः। देवऽयानैः। १५। ऊर्ध्वः। अग्निः। सुऽमतिं। वस्वः। अश्रेत्। प्रतीची। जूर्णिः। देवऽतातिं। ए

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. तिा भेजाते इति। अद्री इति। रथ्याःऽइव। पंथां। ऋतं। होता। नः। इषितः। यजाति। प्र। ववृजे। सुऽप्रयाः। बर्हिः।
५५ एषां। आ। विश्पतीइवेति विश्पतीऽइव। बीरिटे। इयाते इति। विशां। अक्तोः। उषसः। पूर्वऽहूतौ। वायुः। पू-
षा। स्वस्तये। नियुत्वान्। ज्मया। अत्र। वसवः। रंत। देवाः। उरौ। अंतरिक्षे। मर्जयंत। शुभ्राः। अर्वाक्। पथः।
उरुऽज्रयः। कृणुध्वं। श्रोत। दूतस्य। जग्मुषः। नः। अस्य। ते। हि। यज्ञेषु। यज्ञियासः। ऊमाः। सधऽस्थं। विश्वे। या
अभि। संति। देवाः। तान्। अध्वरे। उशतः। यक्षि। अग्ने। श्रुष्टी। भगं। नासत्या। पुरंऽधिं। आ। अग्ने। गिरः।
दिवः। आ। पृथिव्याः। मित्रं। वह। वरुणं। इंद्रं। अग्निं। आ। अर्यमणं। अदितिं। विष्णुं। एषां। सरस्वती। मरु-
तः। मादयंतां। ररे। हव्यं। मतिऽभिः। यज्ञियानां। नक्षत्। कामं। मर्त्यानां। असिन्वन्। धाता। रयिं। अवि॰ ५५

दस्यं। सदाऽसाः। सक्षी महि। युज्येभिः। नु। देवैः। नु। रोदसी इति। अभिस्तुते इत्यभिऽस्तुते। वसिष्ठैः। ऋतऽ
वानः। वरुणः। मित्रः। अग्निः। यच्छन्तु। चन्द्राः। उपऽमं। नः। अर्कं॥ ८॥ ओ इति। श्रुष्टिः। विदथ्या। सं। एतु।
प्रति। स्तोमं। दधीमहि। तुराणां। यत्। अद्य। देवः। सविता। सुवाति। स्याम। अस्य। रत्निनः। विऽभागे।
मित्रः। तत्। नः। वरुणः। रोदसी इति। च। द्युऽभक्तं। इन्द्रः। अर्यमा। ददातु। दिदेष्टु। देवी। अदितिः। रेक्णः। वा
युः। च। यत्। निऽयुवैते इति निऽयुवैते। भगः। च। सः। इत्। तु। उग्रः। अस्तु। मरुतः। सः। शुष्मी। यं। मर्तं। पृष
त्ऽअश्वाः। अवथ। उत। ईं। अग्निः। सरस्वती। जुनन्ति। न। तस्य। रायः। परिऽएता। अस्ति। अयं। हि।
नेता। वरुणः। ऋतस्य। मित्रः। राजानः। अर्यमा। अपः। धुः। इति धुः। सुऽहवा। देवी। अदितिः। अनर्वा। ते।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. नः। अंहः। अति। पर्षन्। अरिष्टान्। अस्य। देवस्य। मीळ्हुषः। वयाः। विष्णोः। एषस्य। प्रऽभृथे। हवि

४७ ःऽभिः। विदे। हि। रुद्रः। रुद्रियं। महिऽत्वं। यासिष्टं। वर्तिः। अश्विनौ। इराऽवत्। मा। अत्र। पूषन्। आघृ

णे। इरस्यः। वरूत्री। यत्। रातिऽसाचः। च। रासन्। मयःऽभुवः। नः। अर्वन्तः। नि। पान्तु। वृष्टिं। परिऽज्मा।

नूरोदसी० वातः। ददातु। ७०॥ प्रातः। अग्निं। प्रातः। इन्द्रं। हवामहे। प्रातः। मित्रावरुणा। प्रातः। अश्विना। प्रातः। भगं। रु

ऋ.रु.१ पूषणं। ब्रह्मणः। पतिं। प्रातरिति। सोमं। उत। रुद्रं। हुवेम। प्रातःऽजितं। भगं। उग्रं। हुवेम। वयं। पुत्रं।

47

अदितेः। यः। विऽधर्ता। आध्रः। चित्। यं। मन्यमानः। तुरः। चित्। राजा। चित्। यं। भगं। भक्षि। इति। आ

ह। भगः। प्रऽनेतः। इति। प्रऽनेतः। भग। सत्यऽराधः। भग। इमां। धियं। उत्। अव। ददत्। नः। भग। प्र। नः। ४०

© Dharmartha Trust J&K. Digitized by eGangotri

नृनृस्या । गोभिः । अश्वैः । भग । प्र । नृऽभिः । नृऽवंतः । स्याम । उत । इदानीं । भगऽवंतः । स्याम । उत । प्रऽपि
त्वे । उत । मध्ये । अह्नां । उत । उत्ऽइता । मघऽवन् । सूर्यस्य । वयं । देवानां । सुऽमतौ । स्याम । भग । एव । भ
गऽवान् । अस्तु । देवाः । तेन । वयं । भगऽवंतः । स्याम । तं । त्वा । भग । सर्वः । इत् । जोहवीति । सः । नः । भग । पु
रःऽएता । भव । इह । सं । अध्वराय । उषसः । नमंत । दधिक्रावाऽइव । शुचये । पदाय । अर्वाचीनं । वसुऽ
विदं । भगं । नः । रथंऽइव । अश्वाः । वाजिनः । आ । वहंतु । अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः
सदं । उछंतु । भद्राः । घृतं । दुहानाः । विश्वतः । प्रऽपीताः । ॥७॥ प्र । ब्रह्माणः । अंगिरसः । नक्षंत । प्र । क्रं
दनुः । नभन्यस्य । वेतु । प्र । धेनवः । उदऽप्रुतः । नवंत । युज्यातां । अद्री इति । अध्वरस्य । पेशः । सुऽगः

यूयं०

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ त्वा।अग्ने।सनःऽवितः।अध्वा।युक्ष्व।सुते।हरितः।रोहितः।च।ये।वा।सद्मन्।अरुषाः।वीरऽवाहः।
४८ हुवे।देवानां।जनिमानि।सत्तः।सं।ऊं इति।वः।यज्ञं।महयन्।नमःऽभिः।प्र।होता।मंद्रः।रिरिचे।उ
सु। पाके।यजस्व।पुरुऽअनीक।देवान्।आ।यज्ञियां।अरमतिं।ववृत्याः।यत्।वीरस्य।रेवतः।दुरोणे।
स्योनऽशीः।अतिथिः।आऽचिकेतत्।सुऽप्रीतः।अग्निः।सुऽधितः।दमे।आ।सः।विशे।दाति।वार्यं।
प इयत्यै।इमं।नः।अग्ने।अध्वरं।जुषस्व।मरुत्ऽसु।इंद्रे।यशसं।कृधि।नः।आ।नक्ता।बर्हिः।सदतां।
उषसा।उशंता।मित्रावरुणा।यज।इह।एव।अग्निं।सहस्यं।वसिष्ठः।रायःऽकामः।विश्वऽप्स्न्यस्य।
स्तोता।इषं।रयिं।पप्रथत्।वाजं।अस्मे इति।७।१।प्र।वः।यज्ञेषु।देवऽयंतः।अर्चन्।द्यावा।नमःऽभिः। ४८

यूयं॰

© Dharmartha Trust J&K. Digitized by eGangotri

पृथिवीइति। इषध्यै। येषां। ब्रह्माणि। असमानि। विप्राः। विष्वक्। विऽयंति। वनिनः। न। शाखाः॥ प्र। यज्ञः। ए
तु। हेत्वः। न। सप्तिः। उत्। यच्छध्वं। सऽमनसः। घृताचीः। स्तृणीत। बर्हिः। अध्वराय। साधु। ऊर्ध्वा। शो
चींषि। देवऽयूनि। अस्थुः॥ आ। पुत्रासः। न। मातरं। विऽभृत्राः। सानौ। देवासः। बर्हिषः। सदंतु। आ। विश्वा
ची। विदथ्यां। अनक्तु। अग्ने। मा। नः। देवऽताता। मृधः। करिति कः॥ ते। सीषपंत। जोषं। आ। यजत्राः। ऋ
तस्य। धाराः। सुऽदुघाः। दुहानाः। ज्येष्ठं। वः। अद्य। महः। आ। वसूनां। आ। गंतन। सऽमनसः। यति। स्थ॥ न
आ। एव। नः। अग्ने। विक्षु। आ। दशस्य। त्वया। वयं। सहसाऽवन्। आस्क्राः। राया। युजा। सधऽमादः। अरिष्टाः
यूयं०॥३॥ दधिऽक्रां। वः। प्रथमं। अश्विना। उषसं। अग्निं। संऽइद्धं। भगं। ऊतये। हुवे। इंद्रं। विष्णुं। पूषणं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ ब्रह्मणः।पतिं।आदित्यान्।द्यावापृथिवी इति।अपः।स्वः।इति।स्वः।दधिऽक्रां।ऊं इति।नमसा।बोधयं
४९ तः।उत्ऽईराणाः।यज्ञं।उपऽप्रयंतः।इळां।देवीं।बर्हिषि।सादयंतः।अश्विना।विप्रा।सुऽहवा।हुवेम।दधि
ऽक्रां।ऊं।बुबुधानः।अग्निं।उप।ब्रुवे।उषसं।सूर्यं।गां।ब्रध्नं।मंश्चतोः।वरुणस्य।बभ्रुं।ते।विश्वा।अ
49 स्मत्।दुःऽइता।यवयंतु।दधिऽक्रावा।प्रथमः।वाजी।अर्वा।अग्रे।रथानां।भवति।प्रऽजानन्।संऽवि
दानः।उषसा।सूर्येण।आदित्येभिः।वसुऽभिः।अंगिरःऽभिः।आ।नः।दधिऽक्राः।पथ्यां।अनक्तु।ऋतस्य।
पथां।अनुऽएतवै।ऊं इति।शृणोतु।नः।दैव्यं।शर्द्धः।अग्निः।शृण्वंतु।विश्वे।महिषाः।अमूराः।१४।आ।
देवः।यातु।सविता।सुऽरत्नः।अंतरिक्षऽप्राः।वहमानः।अश्वैः।हस्ते।दधानः।नर्या।पुरूणि।निऽवेशय ४९

© Dharmartha Trust J&K. Digitized by eGangotri

न्।च।प्रऽसुवन्।च।भूम।उत्।अस्य।बाहू इति।शिथिरा।बृहन्ता।हिरण्ययाः।दिवः।अन्तान्।अनष्टां।नू
नं।सः।अस्य।महिमा।पनिष्ट।सूरः।चित्।अस्मै।अनु।दात्।अपस्यां।सः।घ।नः।देवः।सविता।सहऽ
वा।आ।साविषत्।वसुऽपतिः।वसूनि।विऽश्रयमाणः।अमतिं।उरूचीं।मर्त्तऽभोजनं।अध।रासते।
नः।इमाः।गिरः।सवितारं।सुऽजिह्वं।पूर्णऽगभस्तिं।इळते।सुऽपाणिं।चित्रं।वयः।बृहत्।अस्मे इति।
यूयं० दधातु।०।३२।इमाः।रुद्राय।स्थिरऽधन्वने।गिरः।क्षिप्रऽइषवे।देवाय।स्वधाऽव्ने।अषाळ्हाय।सहमा
नाय।वेधसे।तिग्मऽआयुधाय।भरत।शृणोतु।नः।सः।हि।क्षयेण।क्षम्यस्य।जन्मनः।साम्ऽराज्येन।
दिव्यस्य।चेतति।अवन्।अवन्तीः।उप।नः।दुरः।चर।अनमीवः।रुद्र।जासु।नः।भव।याः।ते।दिद्युत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ पं॰ अवंऽस्र स्पा। दिवः। परि। क्ष्मया। चरंति। परि। त्सा। वृण क्तु। नः। सुह स्रं। ते। स्वुऽअ। पि वा। त। भेषजा। मा

५० नः। तोकेषु। तनयेषु। रिरिषः। मा। नः। वधीः। रुद्र। मा। परा। दाः। मा। ते। भूम। प्रऽसितौ। हीळितस्य।

यूँ॰ यं॰ आ। नः। भज। बर्हिषि। जीवऽशंसे। ओं।।२३।। आपः। यं। वः। प्रथमं। देवऽयंतः। इंद्रऽपानं। ऊर्मिं। अकृ

ण्वत। इंद्रः। तं। वः। वयं। शुचिं। अरिप्रं। अद्य। घृतऽप्रुषं। मधुमंतं। वनेम। तं। ऊर्मिं। आपः। मधुमत्ऽ

तमं। वः। अपां। नपात्। अवतु। आशुऽहेमा। यस्मिन्। इंद्रः। वसुऽभिः। मादयाते। तं। अश्याम। देवऽ

यंतः। वः। अद्य। शतऽपवित्राः। स्वधया। मदंतीः। देवीः। देवानां। अपि। यंति। पाथः। ताः। इंद्रस्य। न।

मिनंति। व्रतानि। सिंधुऽभ्यः। हव्यं। घृतऽवत्। जुहोत। याः। सूर्यः। रश्मिऽभिः। आऽततान। याभ्यः। ५०

50

© Dharmartha Trust J&K. Digitized by eGangotri

यूँयं॰

इंद्रः। अरदत्। गाः। तुं। ऊर्मिं। नो। सिंधवः। वरिवः। धातन। नः॥ ७ ॥ १४ ॥ ऋभुक्षणः। वाजाः। मादयध्वं। अस्मे इ
ति। नरः। मघऽवानः। सुतस्य। आ। वः। अर्वाचः। क्रतवः। न। याताः। विऽभ्वः। रथं। नर्यं। वर्तयंतु॥ ऋभुः। ऋभु
ऽभिः। अभि। वः। स्याम। विऽभ्वः। विभुऽभिः। शवसा। शवांसि। वाजः। अस्मान्। अवतु। वाजऽसाता। इं
द्रेण। युजा। तरुषेम। वृत्रं॥ ते। चित्। हि। पूर्वीः। अभि। संति। शासा। विश्वान्। अर्यः। उपरऽताति। वन्वन्।
इंद्रः। विऽभ्वा। ऋभुक्षाः। वाजः। अर्यः। शत्रोः। मिथत्या। कृणवन्। वि। नृऽमणं॥ नु। देवासः। वरिवः। कर्त
न। नः। भूत। नः। विश्वे। अवसे। सऽजोषाः। सं। अस्मे इति। इषं। वसवः। ददीरन्॥ ८ ॥ १५ ॥ समुद्रऽज्येष्ठाः।
सलिलस्य। मध्यात्। पुनानाः। यंति। अनिऽविशमानाः। इंद्रः। याः। वज्री। वृषभः। ररादः। ताः। आपः।

यएं॰

© Dharmartha Trust J&K. Digitized by eGangotri

तांआपोदेवीरिहमामवंतु॥

प॰पं॰ देवीः।इह।मां।अवंतु।याः।आपः।दिव्याः।उत।वा।स्रवंति।खनित्रिमाः।उत।वा।याः।स्वयंऽजाः।समुद्र
५३ अर्थाः।याः।शुचयः।पावकाः।ग॰।यासां।राजा।वरुणः।याति।मध्ये।सत्यानृते इति।अवऽपश्यन्।राज
ना।नो।मधुऽश्चुतः।शुचयः।याः।पावकाः।ग॰।यासु।राजा।वरुणः।यासु।सोमः।विश्वे।देवाः।यासु
ऊर्जं।मदंति।वैश्वानरः।यासु।अग्निः।प्रऽविष्टः।ग॰।१धा।आ।मां।मित्रावरुणा।इह।रक्षतं।कुलाय
यत्।विश्वयत्।मा।नः।आ।गन्।अजकाऽवं।दुःऽदृशीकं।तिरः।दधे।मा।मां।पद्येन।रपसा।विद
त्।त्सरुः।यत्।विजामन्।पदुषि।वंदनौ।भुवत्।अष्ठीवंतौ।परि।कुल्फौ।च।देहत्।अग्निः।तत्।
शोचेन।अप।बाधतां।इतः।ग॰।यत्।शल्मलौ।भवति।यत्।नदीषु।यत्।ओषधीभ्यः।परि।जायते। ५३

मामांपद्येनरपसाविदत्सरुः॥

© Dharmartha Trust J&K. Digitized by eGangotri

विषं।विश्वे।देवाः।निः।इतः।तत्।सुवंतु।०।याः।प्रऽवतः।निऽवतः।उत्ऽवतः।उदन्ऽवतीः।अनुदकाः।च।
याः।ताः।अस्मभ्यं।पयसा।पिन्वमानाः।शिवाः।देवीः।अशिपदाः।भवंतु।सर्वाः।नद्यः।अशिमि
दाः।भवंतु।।१७।।आदित्यानां।अवसा।नूतनेन।सक्षीमहि।शर्मणा।शंऽतमेन।अनागाःऽत्वे।अ
दितिऽत्वे।तुरासः।इमं।यज्ञं।दधतु।श्रोषमाणाः।आदित्यासः।अदितिः।मादयंतां।मित्रः।अर्यमा।
वरुणः।रजिष्ठाः।अस्माकं।संतु।भुवनस्य।गोपाः।पिबंतु।सोमं।अवसे।नः।अद्य।आदित्याः।
विश्वे।मरुतः।च।विश्वे।देवाः।च।विश्वे।ऋभवः।च।विश्वे।इंद्रः।अग्निः।अश्विना।तुस्तुवानाः।०। यूयं०
१८।।आदित्यासः।अदितयः।स्याम।पूः।देवऽत्रा।वसवः।मर्त्यऽत्रा।सनेम।मित्रावरुणा।सनंतः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. भवेम। द्यावा। पृथिवी इति। भवंतं। नः। ० मम। हंतु। शर्म्म। तोकाय। तनयाय। गोपाः। मा। वः। भुजेम। अन्य
५२ ऽजातं। एनः। मा। तत्। कर्म। वसवः। यत्। चयध्वे। तुरण्यवः। अंगिरसः। नक्षंत। रत्नं। देवस्य। सवि
तुः। इयानाः। पिता। च। यत्। नः। महान्। यजत्रः। विश्वे। देवाः। सऽमनसः। जुषंत॥३१॥७॥ नमःऽभिः।
52 सऽबाधः। इद्धः। बृहती इति। यजत्रे इति। ते इति। चित्। हि। पूर्वी। कवयः। गृणंतः। पुरः। मही इति। दधि
रे। देवपुत्रे इति देवऽपुत्रे। प्र। पूर्वजे इति पूर्वऽजे। पितरा। नव्यसीभिः। गीःऽभिः। कृणुध्वं। सदने इति।
ऋतस्य। आ। नः। द्यावापृथिवी इति। दैव्येन। जनेन। यातं। महि। वां। वरूथं। उलो इति। वां। हि। रत्नऽ
धेयानि। संति। पुरूणि। द्यावापृथिवी इति। सुऽदासे। अस्मे इति। धत्तं। यत्। असत्। अस्कृधोयु। ५२

© Dharmartha Trust J&K. Digitized by eGangotri

यूयं॰ ॥ २० ॥ वास्तोः । पते । प्रति । जानीहि । अस्मान् । सुऽआवेशः । अनमीवः । भव । नः । यत् । त्वा । ईमहे । प्रति ।
तत् । नः । जुषस्व । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे । वास्तोः । पते । प्रऽतरणः । नः । एधि । गयऽस्फानः । गो
भिः । अश्वेभिः । इन्दो इति । अजरासः । ते । सख्ये । स्याम । पिताऽइव । पुत्रान् । [illegible] स्व । प्रति । नः । जु
षस्व । वास्तोः । पते । शग्मया । सम्ऽसदा । ते । सक्षीमहि । रण्वया । गातुऽमत्या । पाहि । क्षेमे । उत । योगे । वरम् ।
यूयं॰ नः ॥ ३ ॥ २१ ॥ अमीवऽहा । वास्तोः । पते । विश्वा । रूपाणि । आऽविशन् । सखा । सुऽशेवः । एधि । नः । यत् ।
अर्जुन । सारमेय । दतः । पिशङ्ग । यच्छसे । विऽइव । भ्राजन्ते । ऋष्टयः । उप । स्रक्वेषु । बप्सतः । नि । सु । स्व
प । स्तेनम् । राय । सारमेय । तस्करम् । वा । पुनःऽसर । स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽय

© Dharmartha Trust J&K. Digitized by eGangotri

सोतृनिंद्रस्वसाजसिकिमस्मादुदुस्तुनायस्नेनिषुस्वप॥

निषुस्वप॥

प॰पं॰ सोऽ॥०॥लोऽस्र्कुरस्या। दूद्दूहि। नवा। दुर्द्दतु। स्र्कुरः॥०॥सस्तु। माता। सस्तु। पिता। सस्तु। श्वा। सस्तु। विश्प

५३ तिः। सस्संतु। सर्वे। ज्ञातयः। सस्तु। अयं। अभितः। जनः। यः। आस्ते। यः। च। चरति। यः। च। पश्यति। नः।

जनः। तेषां। सं। हन्मः। अक्षाणि। यथा। इदं। हर्म्यं। तथा। सहस्रऽशृंगः। वृषभः। यः। समुद्रात्। उत्ऽआ

चरत्। तेन। सहस्येन। वयं। नि। जनान्। स्वापयामसि। प्रोष्ठेऽशयाः। वह्येऽशयाः। नारीः। याः। तल्पऽ

शीवरीः। स्त्रियः। याः। पुण्यऽगंधाः। ताः। सर्वाः। स्वापयामसि॥ स्वा। को। ई। विऽअंक्ताः। नरः। सऽनी

काः। रुद्रस्य। मर्याः। अध। स्वऽअश्वाः। नकिः। हि। एषां। जनूंषि। वेद। ते। अंग। विद्रे। मिथः। जनित्रं।

अभि। स्वऽपूभिः। मिथः। वपंत। वातऽस्वनसः। श्येनाः। अस्पृध्रन्। एतानि। धीरः। निण्या। चिकेत। ५३

© Dharmartha Trust J&K. Digitized by eGangotri

पृश्निः। यत्। ऊधः। मही। जभार। सा। विट्। सुऽवीरा। मरुत्ऽभिः। अस्तु। सनात्। सहन्ती। पुष्यन्ती। नृम्णं। या
मं। येष्ठाः। शुभा। शोभिष्ठाः। श्रिया। संऽमिश्लाः। ओजःऽभिः। उग्राः। उग्रं। वः। ओजः। स्थिरा। शवांसि। अ
ध। मरुत्ऽभिः। गणः। तुविष्मान्। शुभ्रः। वः। शुष्मः। क्रुध्मी। मनांसि। धुनिः। मुनिःऽइव। शर्द्धस्य। धृष्णोः।
सनेमि। अस्मत्। युयोत। दिद्युं। मा। वः। दुःऽमतिः। इह। प्रणक्। नः। प्रिया। वः। नाम। हुवे। तुराणां। आ। य
त्। तृपत्। मरुतः। वावशानाः।। २३।। सुऽआयुधासः। इष्मिणः। सुऽनिष्काः। उत। स्वयं। तन्वः। शुम्भमानाः।
शुची। वः। हव्या। मरुतः। शुचीनां। शुचिं। हिनोमि। अध्वरं। शुचिऽभ्यः। ऋतेन। सत्यं। ऋतऽसापः। आ
यन्। शुचिऽजन्मानः। शुचयः। पावकाः। अंसेषु। आ। मरुतः। खादयः। वः। वक्षःऽसु। रुक्माः। उपऽशि

© Dharmartha Trust J&K. Digitized by eGangotri

१·पं· श्रियाणाः। शिमिऽविद्युतः। न। वृष्टिऽभिः। रुचानाः। अनु। स्वधां। आयुधैः। यच्छमानाः। प्राबुध्या। वः। ईरते।
५४ महांसि। नामानि। प्रऽयज्यवः। तिरध्वं। सहस्रियं। दम्यं। भागं। एतं। गृहऽमेधीयं। मरुतः। जुषध्वं। य
दि। स्तुतस्य। मरुतः। अधिऽइथ। इत्था। विप्रस्य। वाजिनः। हवीमन्। मक्षु। रायः। सुऽवीर्यस्य। दात। नु
चित्। यं। अन्यः। आऽदभत्। अरावा।। २४।। अत्यासः। न। ये। मरुतः। सुऽअंचः। यक्षऽदृशः। न। शुभयं
त। मर्याः। ते। हर्म्येऽस्थाः। शिशवः। न। शुभ्राः। वत्सासः। न। प्रऽक्रीळिनः। पयःऽधाः। दशस्यंतः। नः। म
रुतः। मृळंतु। वरिवस्यंतः। रोदसी इति। सुमेके इति सुऽमेके। आरे। गोऽहा। नृऽहा। वधः। वः। अस्तु। सु
म्नेभिः। अस्मे इति। वसवः। नमध्वं।। आ। वः। होता। जोहवीति। सत्तः। सत्राचीं। रातिं। मरुतः। गृणानः। ५५

© Dharmartha Trust J&K. Digitized by eGangotri

यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः । इमे । तुरं । मरुतः । रमयंति । इमे । स

हः । सहसः । आ । नमंति । इमे । शंसं । वनुष्यतः । नि । पांति । गुरु । द्वेषः । अररुषे । दधंति । इमे । रध्रं । चित् । म

रुतः । जुनंति । भृमिं । चित् । यथा । वसवः । जुषंत । अप । बाधध्वं । वृषणः । तमांसि । धत्त । विश्वं । तनयं । तो

कं । अस्मे इति । ४ । मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दध्म । रथ्यः । विऽभागे । आ ।

नः । स्पार्हे । भजतन । वसव्ये । यत् । ईं । सुऽजातं । वृषणः । वः । अस्ति । सं । यत् । हनंत । मन्युऽभिः । जनासः ।

शूराः । यह्वीषु । ओषधीषु । विक्षु । अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ।

भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यंते । पुरा । चित् । मरुत्ऽभिः । उग्रः । पृतनासु । सा

© Dharmartha Trust J&K. Digitized by eGangotri

१ पं. ळ्हा। मुरुत्ऽभिः। इत्। सनिता। वाजं। अर्वा। अस्मे इति। वीरः। मरुतः। शुष्मी। अस्तु। जनानां। यः। असुरः।
५५ विऽधर्ता। अपः। येन। सुऽक्षितये। तरेम। अध। स्वं। ओकः। अभि। वः। स्याम। ०ौ। २५। मध्वः। वः। नाम। मा तन्न इन्द्रो.
रुतं। यजत्राः। प्र। यज्ञेषु। शवसा। मदंति। ये। रेजयंति। रोदसी इति। चित्। उर्वी इति। पिन्वंति। उत्सं। यत्।
अयासुः। उग्राः। निऽचेतारः। हि। मरुतः। गृणंतं। प्रऽनेतारः। यजमानस्य। मन्म। अस्माकं। अद्य। वि
दथेषु। बर्हिः। आ। वीतये। सदत। पिप्रियाणाः। न। एतावत्। अन्ये। मरुतः। यथा। इमे। भ्राजंते। रुक्मैः।
आयुधैः। तनूभिः। आ। रोदसी इति। विश्वऽपिशः। पिशानाः। समानं। अंजि। अंजते। शुभे। कं। ऋध
क्। सा। वः। मरुतः। दिद्युत्। अस्तु। यत्। वः। आगः। पुरुषता। कराम। मा। वः। तस्यां। अपि। भूम। यज ५५

© Dharmartha Trust J&K. Digitized by eGangotri

पू॰सं॰

त्राः। अस्मे इति। वः। अस्तु। सुऽमतिः। चनिष्ठा॥ ऋते। चित्। अत्र। मरुतः। रणन्त। अनवद्यासः। शुचयः।
पावकाः। प्र। नः। अवत। सुमतिऽभिः। यजत्राः। प्र। वाजेभिः। तिरत। पुष्यसे। नः॥ उत। स्तुतासः। मरुतः।
व्यन्तु। विश्वेभिः। नामऽभिः। नरः। हवींषि। ददात। नः। अमृतस्य। प्रऽजायै। जिगृत। रायः। सूनृता। मघा
नि॥ आ। स्तुतासः। मरुतः। विश्वे। ऊती। अच्छ। सूरीन्। सर्वऽताता। जिगात। ये। नः। त्मना। शतिनः। वर्द्ध
यन्ति॥ ७॥ २७॥ प्र। साकम्ऽउक्षे। अर्चत। गणाय। यः। दैव्यस्य। धाम्नः। तुविष्मान्। उत। क्षोदन्ति। रोदसी
इति। महिऽत्वा। नक्षन्ते। नाकम्। निःऽऋतेः। अवंशात्॥ जनूः। चित्। वः। मरुतः। त्वेष्येण। भीमासः। तुवि
ऽमन्यवः। अयासः। प्र। ये। महःऽभिः। ओजसा। उत। सन्ति। विश्वः। वः। यामन्। भयते। स्वःऽदृक्॥ बृह

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. त् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिं । नः । गतः । न । अध्वा । वि । तिराति ।
५६ जंतुं । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत । युष्माऽऊतः । विप्रः । मरुतः । शतस्वी । युष्माऽऊतः । अर्वा ।
सहुरिः । सहस्री । युष्माऽऊतः । संऽराट् । उत । हंति । वृत्रं । प्र । तत् । वः । अस्तु । धूतयः । देष्णं । तान् । आ । रुद्रस्य ।
56
मीळ्हुषः । विवासे । कुवित् । नंसंते । मरुतः । पुनः । नः । यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् ।
एनः । ईमहे । तुराणां । प्र । सा । वाचि । सुऽस्तुतिः । मघोनां । इदं । सुऽउक्तं । मरुतः । जुषंत । आरात् । चित् । द्वेषः । वृ-
सूक्तं० षणः । युयोत । ० । २ । यं । त्रायध्वे । इदंऽइदं । देवासः । यं । च । नयथ । तस्मै । अग्ने । वरुण । मित्र । अर्यमन् । म-
रुतः । शर्म । यच्छत । ईजानः । तरति । द्विषः । प्र । सः । क्षयं । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति । नहि । ५६

युष्माकं·

© Dharmartha Trust J&K. Digitized by eGangotri

वः। चरमं। चन। वसिष्ठः। परि। मंसते। अस्माकं। अद्य। मरुतः। सुते। सचा। विश्वे। पिबत। कामिनः। नहि।
वः। ऊतिः। पृतना। सु। मर्द्धति। यस्मै। अराध्वं। नरः। अभि। वः। आ। अवर्त्। सुऽमतिः। नवीयसी। तूयं। यात।
३ तूं। पिपीषवः। ओ इति। घृष्विऽराधसः। यातन। अंधांसि। पीतये। इमा। वः। हव्या। मरुतः। ररे। हि। कं। मो इति।
सु। अन्यत्र। गंतन। आ। च। नः। बर्हिः। सदत। अविता। च। नः। स्पार्हाणि। दातवे। वसु। अस्रेधंतः।
मरुतः। सोम्ये। मधौ। स्वाहा। इह। मादयाध्वै।। २०।। सस्वरिति। चित्। हि। तन्वः। शुंभमानाः। आ। हंसासः।
नीलऽपृष्ठाः। अपप्तन्। विश्वं। शर्द्धः। अभितः। मा। नि। सेद। नरः। न। रण्वाः। सवने। मदंतः। यः। नः। मरुतः।
अभि। दुःऽहृणायुः। तिरः। चित्तानि। वसवः। जिघांसति। द्रुहः। पाशान्। प्रति। सः। मुचीष्ट। तपिष्ठेन। ह

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. न्मनाः। हृतुनाता। सांऽतपनाः। इदं। हविः। मरुतः। तत्। जुजुष्टन। युष्माक। ऊती। रिशादसः। गृहऽमेधासः।
५८ आ। गत। मरुतः। मा। अप। भूतन। युष्माक। ऊती। सुऽदानवः। इह। इह। वः। स्वऽतवसः। कवयः। सूर्यऽत्व
चः। यज्ञं। मरुतः। आ। वृणे। त्र्यंबकं। यजामहे। सुऽगंधिं। पुष्टिऽवर्धनं। उर्वारुकंऽइव। बंधनात्। मृत्योः। मुक्षीय। मा।
अमृतात्॥३०॥ इति पंचमाष्टके चतुर्थोध्यायः॥ ॐ ऋ॥ यदद्य मैत्रावरुणं तु वै सौर्यो द्या ह्मसप्तोसूर्यः षका
द्या स्तिस्त्रः सौर्यं उद्वेति तिस्रो चार्द्धं पंच मादिवि पंच प्रतिवां प्रमित्रयोरे कोनागा यज्ञं दशाम्यादयस्त्रयः प्रगा
थाः पुरुद्ब्हि कं चतुर्थ्यां याद शादि स्यास्तिस्रः सौर्यः प्रतिवां दशाश्विनं तु तदा शुभानव सप्ताद्या विरा
ज आवां रथो द्वाचा विश्ववाराः सप्ता प स्व सुः षका गोमता पंचा नारि ष्येमा उवां षट् प्रागाथं स्नुषा अद्या ५८

© Dharmartha Trust J&K. Digitized by eGangotri

उपस्यंनुवां।उदुस्रत्तोपोरुरुचेषट्।प्रतिपंचव्युषाः प्रतितरचैं॥ ॐ॥ यत्।अद्य।सूर्य।ब्रवः।अनागाः।उत्ऽ
यन्।मित्राय।वरुणाय।सत्यं।वयं।देवऽत्रा।अदिते।स्याम।तव।प्रियासः।अर्यमन्।गृणंतः।एषः।स्यः।
२ मित्रावरुणा।नृऽचक्षाः।उभे इति।उत्।एति।सूर्यः।अभि।त्मना।विश्वस्य।स्थातुः।जगतः।च।गोपाः।ऋ
जु।मर्तेषु।वृजिना।च।पश्यन्।अयुक्त।सप्त।हरितः।सधऽस्थात्।याः।ईं।वहंति।सूर्यं।घृताचीः।धामा
नि।मित्रावरुणा।युवाकुः।सं।यः।यूथाऽइव।जनिमानि।चष्टे।उत्।वां।पृक्षासः।मधुऽमंतः।अस्थुः।
आ।सूर्यः।अरुहत्।शुक्रं।अर्णः।यस्मै।आदित्याः।अध्वनः।रदंति।मित्रः।अर्यमा।वरुणः।सऽजोषाः॥
इमे।चेतारः।अनृतस्य।भूरेः।मित्रः।अर्यमा।वरुणः।हि।संति।इमे।ऋतस्य।ववृधुः।दुरोणे।शग्माः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ सः। पुत्रात्। अदितेः। अदब्धाः। इमे। मित्रः। वरुणः। दुःऽदभासः। अचेतसं। चित्। चितयन्ति। दक्षैः। अपि।
५८ क्रतुं। सुऽचेतसं। वतन्तः। तिरः। चित्। अंहः। सुऽपथा। नयन्ति॥ ३॥ इमे। दिवः। अनिऽमिषा। पृथिव्याः। चिकि
त्वांसः। अचेतसं। नयन्ति। प्रऽव्राजे। चित्। नद्यः। गाधं। अस्ति। पारं। नः। अस्य। विष्पितस्य। पर्षन्। यत्। गो
58 पावत्। अदितिः। शर्म। भद्रं। मित्रः। यच्छन्ति। वरुणः। सुऽदासे। तस्मिन्। आ। तोकं। तनयं। दधानाः। मा। कु
र्म। देवऽहेळनं। तुरासः। अव। वेदिं। होत्राभिः। यजेत। रिपः। काः। चित्। वरुणऽध्रुतः। सः। परि। द्वेषःऽभिः। अ
र्यमा। वृणक्तु। उरुं। सुऽदासे। वृषणौ। ऊंऽइति। लोकं।०। संऽवृतिः। त्वेषीः। एषां। अपीच्येन। सहसा। सहन्ते।
युष्मत्। भिया। वृषणः। रेजमानाः। दक्षस्य। चित्। महिना। मृळत। नः। यः। ब्रह्मणे। सुऽमतिं। आऽयजाते। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

वाजस्य।सातौ।परमस्य।रायः।सीक्षंत।मन्युं।मघऽवानः।अर्यः।उरु।क्षयाय।चक्रिरे।सुऽधातु।इयं।दे
वा।पुरःऽहितिः।युवऽभ्यां।यज्ञेषु।मित्रावरुणौ।अकारि।विश्वानि।दुःऽगा।पिपृतं।तिरः।नः।१२।५।उत्।
वां।चक्षुः।वरुण।सुऽप्रतीकं।देवयोः।एति।सूर्यः।ततन्वान्।अभि।यः।विश्वा।भुवनानि।चष्टे।सः।मन्युं।
मर्त्येषु।आ।चिकेत।प्र।वां।सः।मित्रावरुणौ।ऋतऽवा।विप्रः।मन्मानि।दीर्घऽश्रुत्।इयर्ति।यस्य।ब्रह्मा
णि।सुक्रतू इति सुऽक्रतू।अवाथः।आ।यत्।क्रत्वा।न।शरदः।पृणैथे इति।प्र।उरोः।मित्रावरुणा।पृथि
व्याः।प्र।दिवः।ऋष्वात्।बृहतः।सुदानू इति सुऽदानू।स्पशः।दधाथे इति।ओषधीषु।विक्षु।ऋधक्।यतः।
। [illegible] अनिःमिषं।रक्षमाणा।शंसा।मित्रस्य।वरुणस्य।धाम।शुष्मः।रोदसी इति।बद्धे।महिऽत्वा।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. अयन्।मासाः।अयज्वनां।अवीराः।प्र।यज्ञऽमन्मा।वृजनं।तिराते।अमूरा।विश्वा।वृषणौ।इमाः।वां।

५९ न।यासु।चित्रं।ददृशे।न।यक्षं।द्रुहः।सचंते।अनृता।जनानां।न।वां।निण्यानि।अचिते।अभूवन्।

59 सं।ऊं इति।वां।यज्ञं।महयं।नमःऽभिः।हुवे।वां।मित्रावरुणा।सऽबाधः।प्र।वां।मन्मानि।ऋचसे।

नवानि।कृतानि।ब्रह्म।जुजुषन्।इमानि।०।।३।।उत्।उ।सूर्यः।बृहत्।अर्चींषि।अश्रेत्।विश्वा।ज

निम।मानुषाणां।समः।दिवा।ददृशे।रोचमानः।क्रत्वा।कृतः।सुऽकृतः।कर्तृऽभिः।भूत्।सः।सू

र्य।प्रति।पुरः।नः।उत्।गाः।एभिः।स्तोमेभिः।एतशेभिः।एवैः।प्र।नः।मित्राय।वरुणाय।वोचः।अ

नागसः।अर्यम्णे।अग्नये।च।वि।नः।सहस्रं।शुरुधः।रदंतु।ऋतऽवानः।वरुणः।मित्रः।अग्निः।० ५९

© Dharmartha Trust J&K. Digitized by eGangotri

आ। नः। कामं। पूपुरंतु। स्तवानाः। द्यावाभूमी इति। अदिते। त्रासीथां। नः। ये। वां। जज्ञुः। सुऽजनिमानः।
ऋष्वे इति। मा। हेळे। भूम। वरुणस्य। वायोः। मा। मित्रस्य। प्रियऽतमस्य। नृणां। प्र। बाहवा। सिसृतं।
जीवसे। नः। आ। नः। गव्यूतिं। उक्षतं। घृतेन। आ। नः। जने। श्रवयतं। युवाना। श्रुतं। मे। मित्रावरुणा।
हवा। इमा। नु। मित्रः। वरुणः। अर्यमा। नः। त्मने। तोकाय। वरिवः। दधंतु। सुऽगा। नः। विश्वा। सुऽपथा
नि। संतु। ०। ५। उत्। ऊं इति। एति। सुऽभगः। विश्वऽचक्षाः। साधारणः। सूर्यः। मानुषाणां। चक्षुः।
मित्रस्य। वरुणस्य। देवः। चर्मऽइव। यः। संऽअविव्यक्। तमांसि। ०। प्रऽसविता। जनानां। महान्।
केतुः। अर्णवः। सूर्यस्य। समानं। चक्रं। परिऽआविवृत्सन्। यत्। एतशः। वहति। धूःऽसु। युक्तः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. विऽभ्राजमानः। उषसां। उपऽस्थात्। रेभैः। उत्। एति। अनुऽमद्यमानः। एषः। मे। देवः। सविता। चच्छंद।
६० यः। समानं। न। प्रऽमिनाति। धाम। दिवः। रुक्मः। उरुऽचक्षाः। उत्। एति। दूरेऽअर्थः। तरणिः। भ्राजमा
नः। नूनं। जनाः। सूर्येण। प्रऽसूताः। अयन्। अर्थानि। कृणवन्। अपांसि। यत्र। चक्रुः। अमृताः।
60 गातुं। अस्मै। श्येनः। न। दीयन्। अनु। एति। पाथः। प्रति। वां। सूरे। उत्ऽइते। विधेम। नमःऽभिः। मि
त्रावरुणा। उत। हव्यैः। ॥५॥ दिवि। क्षयंता। रजसः। पृथिव्यां। प्र। वां। घृतस्य। निःऽनिजः। ददीरन्।
हव्यं। नः। मित्रः। अर्यमा। सुऽजातः। राजा। सुऽक्षत्रः। वरुणः। जुषंत। आ। राजाना। महः। ऋतस्य।
गोपा। सिंधुपती इति सिंधुऽपती। क्षत्रिया। यातं। अर्वाक्। इळां। नः। मित्रावरुणा। उत। वृष्टिं। ६०

© Dharmartha Trust J&K. Digitized by eGangotri

अव। दिवः। इन्वतं। जीरदानू इति जीरऽदानू। ०। देवः। अर्यः। प्र। साधिष्ठेभिः। पथिऽभिः। नयन्तु। ब्रव
त्। यथा। नः। आत्। अरिः। सुऽदासे। इषा। मदेम। सह। देवऽगोपाः। यः। वां। गर्तं। मनसा। तक्षत्। एतं।
ऊर्ध्वां। धीतिं। कृणवत्। धारयत्। च। उक्षेथां। मित्रावरुणा। घृतेन। ता। राजाना। सुऽक्षितीः। तर्प
येथां। एषः। स्तोमः। वरुण। मित्र। तुभ्यं। सोमः। शुक्रः। न। वायवे। अयामि। ०। द्। ०। सुऽसूक्तैः। मित्रं। हुवे।
वरुणं। पूतऽदक्षं। ययोः। असुर्यं। अक्षितं। ज्येष्ठं। विश्वस्य। यामन्। आऽचिता। जिगत्नु। ता। हि। देवा
नां। असुरा। तौ। अर्या। ता। नः। क्षितीः। करतं। ऊर्जयन्तीः। अश्याम। मित्रावरुणा। वयं। वां। द्यावा।
च। यत्र। पीपयन्। अहा। च। ता। भूरिऽपाशौ। अनृतस्य। सेतू इति। दुरत्येतू इति दुःऽअत्येतू। रिप

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. वे।मर्त्याय।ऋतस्य।मित्रावरुणा।पथा।वां।अपः।न।नावा।दुःऽइता।तरेम।आ।नः।मित्रावरुणा।ह

६१ व्यऽजुष्टिं।घृतैः।गव्यूतिं।उक्षतं।इळाभिः।प्रति।वां।अत्र।वरं।आ।जनाय।पृणीतं।उद्नः।दिव्यस्य।

चारोः।०।०।प्र।मित्रयोः।वरुणयोः।स्तोमः।नः।एतु।शूष्यः।नमस्वान्।तुविऽजातयोः।या।धारयं

61 ता।देवाः।सुऽदक्षा।दक्षऽपितरा।असुर्याय।प्रऽमहसा।ता।नः।स्तिऽपा।तनूऽपा।वरुण।जरितॄणां।

मित्र।साधयतं।धियः।यत्।अद्य।सूरे।उत्ऽइते।अनागाः।मित्रः।अर्यमा।सुवाति।सविता।भ

गः।सुप्रऽअवीः।अस्तु।सः।क्षयः।प्र।नु।यामन्।सुऽदानवः।ये।नः।अंहः।अतिऽपिप्रति।०।उत।स्व

ऽराजः।अदितिः।अदब्धस्य।व्रतस्य।ये।महः।राजानः।ईशते।०।मित्रं।गृणीषे।वरुणं।अर्यमणं।रि ६१

© Dharmartha Trust J&K. Digitized by eGangotri

शादसं । राया । हिरण्यऽया । मतिः । इयं । अवृकाय । शवसे । इयं । विप्रा । मेधऽसातये । ते । स्याम । दे

व । वरुण । ते । मित्र । सूरिऽभिः । सह । इषं । स्वरिति स्वः । च । धीमहि । बहवः । सूरऽचक्षसः । अग्निऽजि

ह्वाः । ऋतऽवृधः । त्रीणि । ये । येमुः । विदथानि । धीतिऽभिः । विश्वानि । परिभूतिऽभिः । ९ । वि । ये । दधुः ।

शरदं । मासं । आत् । अहः । यज्ञं । अक्तुं । च । आत् । ऋचं । अनाप्यं । वरुणः । मित्रः । अर्यमा । क्षत्रं । राजा

नः । आशत । तत् । वः । अद्य । मनामहे । सुऽउक्तैः । सूरे । उत्ऽइते । यत् । ओहते । वरुणः । मित्रः । अर्यमा ।

यूयं । ऋतस्य । रथ्यः । ऋतऽवानः । ऋतऽजाताः । ऋतऽवृधः । घोरासः । अनृतऽद्विषः । तेषां । वः । सु

म्ने । सुछर्दिःऽतमे । नरः । स्याम । ये । च । सूरयः । उत् । ऊं इति । त्यत् । दर्शतं । वपुः । दिवः । एति । प्रतिऽह्

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. रायत्।ई।आशुः।वहन्ति।देवः।एतशः।विश्वस्य।चक्षसे।अरं।शीर्ष्णः।शीर्ष्णः।जगतः।तस्थुषः।
६२ पतिं।सुमयो।विश्वं।आ।रजः।सप्त।स्वसारः।सुवितायं।सूर्यं।वहन्ति।हरितः।रथे॥१॥तत्।च
क्षुः।देवऽहितं।शुक्रं।उत्ऽचरत्।पश्येम।शरदः।शतं।जीवेम।शरदः।शतं।काव्येभिः।अदाभ्या।आ
।यातं।वरुणा।द्युऽमत्।मित्रः।च।सोमऽपीतये।दिवः।धामऽभिः।वरुणा।मित्रः।च।आ।यातं।अ
द्रुहा।पिबतं।सोमं।आतुजी।इत्याऽतुजी।आ।यातं।मित्रावरुणा।जुषाणौ।आऽहुतिं।नरा।॥२॥
।प्राति।वां।रथं।नृऽपती।इतिनृऽपती।जरध्यै।हविष्मता।मनसा।यज्ञियेन।यः।वां।दूतः।न।धि
ष्ण्यौ।अजीगः।अच्छ।सूनुः।न।पितरा।विवक्मि।अशोचि।अग्निः।संऽइधानः।अस्मेऽइति।उ ६२

© Dharmartha Trust J&K. Digitized by eGangotri

पोइति।अदृश्रन्।तमसः।चित्।अंताः।अचेति।केतुः।उषसः।पुरस्तात्।श्रिये।दिवः।दुहितुः।जाय
मानः।अभि।वां।नूनं।अश्विना।सुऽहोता।स्तोमैः।सिसक्ति।नासत्या।विवक्वान्।पूर्वीभिः।यातं।
पथ्याभिः।अर्वाक्।स्वःऽविदा।वसुऽमता।रथेन।अवोः।वां।नूनं।अश्विना।युवाकुः।हुवे।यत्।वां।
सुते।माध्वीइति।वसुऽयुः।आ।वां।वहंतु।स्थविरासः।अश्वाः।पिबाथः।अस्मेइति।सुऽसुता।म
धूनि।प्राचीं।ऊंइति।देवा।अश्विना।धियं।मे।अमृध्रां।सातये।कृतं।वसुऽयुं।विश्वाः।अविष्टं।वा
जे।आ।पुरंऽधीः।ता।नः।शक्तं।शचीपतीइति।शचीऽपती।शचीभिः।।२।।अविष्टं।धीषु।अश्वि
ना।नः।आसु।प्रजाऽवत्।रेतः।अह्रयं।नः।अस्तु।आ।वां।तोके।तनये।तूतुजानाः।सुऽरत्नासः

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. देवऽवीतिं। गमेम। एषः। स्यः। वां। पूर्वगत्वाऽइव। सख्ये। निऽधिः। हितः। माध्वी इति। रातः। अस्मे इति।
६३ अहेळता। मनसा। आ। यातं। अर्वाक्। अश्नंता। हव्यं। मानुषीषु। विक्षु। एकस्मिन्। योगे। भुरणा।
समाने। परि। वां। सप्त। स्रवतः। रथः। गात्। न। वायंति। सुऽभ्वः। देवऽयुक्ताः। ये। वां। धूःऽसु। तरणयः।
वहंति। असश्चता। मघवत्ऽभ्यः। हि। भूतं। ये। राया। मघऽदेयं। जुनंति। प्र। ये। बंधुं। सूनृताभिः। तिरं
ते। गव्या। पृंचंतः। अश्व्या। मघानि। नु। मे। हवं। आ। शृणुतं। युवाना। यासिष्टं। वर्तिः। अश्विनौ। इरा
ऽवत्। धत्तं। रत्नानि। जरतं। च। सूरीन्। ॥ ३॥ आ। शुभ्रा। यातं। अश्विना। सुऽअश्वा। गिरः। दस्रा।
जुजुषाणा। युवाकोः। हव्यानि। च। प्रतिऽभृता। वीतं। नः। प्र। वां। अंधांसि। मद्यानि। अस्थुः। अरं। ग ६३

63

© Dharmartha Trust J&K. Digitized by eGangotri

तं । हविष्मः । वीतये । मे । तिरः । अर्यः । हवनानि । श्रुतं । नः । प्र । वां । रथः । मनःऽजवाः । इयर्त्ति । तिरः । रजांसि । अ
श्विना । शतऽऊतिः । अस्मभ्यं । सूर्यावसू इति सूर्याऽवसू । इयानः । अयं । ह । यत् । वां । देवऽयाः । ऊं इति । अद्रिः । ऊर्ध्वः ।
विवक्ति । सोमऽसुत् । युवऽभ्यां । आ । वल्गू इति । विप्रः । ववर्तीत । हव्यैः । चित्रः । ह । यत् । वां । भोजनं । नु । अ
स्ति । नि । अत्रये । महिष्वन्तं । युयोतं । यः । वां । ओमानं । दधते । प्रियः । सन् । १ । उत । त्यत् । वां । जुरते । अ
श्विना । भूत् । च्यवानाय । प्रतीत्यं । हविःऽदे । अधि । यत् । वर्पः । इतःऽऊति । धत्थः । उत । तं । भुज्युं । अश्वि
ना । सखायः । मध्ये । जहुः । दुःऽएवासः । समुद्रे । निः । ईं । पर्षत् । अरावा । यः । युवाकुः । वृकाय । चित् । ज
समानाय । शक्तं । उत । श्रुतं । शयवे । हूयमाना । यौ । अघ्न्यां । अपिन्वतं । अपः । न । स्तर्यं । चित् । शक्ती ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. अश्विना । शचीभिः । एषः । स्यः । कारुः । जरते । सुऽउक्तैः । अग्रे । बुधानः । उषसां । सुऽमन्मा । इषा । तं । वर्द्ध
६४ त् । अघ्न्या । पयःऽभिः ॥ ७ ॥ १५ ॥ आ । वां । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृषऽभिः । अश्वैः । यातु ।
घृतऽवर्तनिः । पविऽभिः । रुचानः । इषां । वोळ्हा । नृऽपतिः । वाजिनीऽवान् । सः । पप्रथानः । अभि । पंच । भूम
64 मा । त्रिऽवंधुरः । मनसा । आ । यातु । युक्तः । विशः । येन । गच्छथः । देवऽयंतीः । कुत्र । चित् । यामं । अश्विना ।
दधाना । सुऽअश्वा । यशसा । आ । यातं । अर्वाक् । दस्रा । निऽधिं । मधुऽमंतं । पिबाथः । वि । वां । रथः । वधू
ध्वा । यादमानः । अंतान् । दिवः । बाधते । वर्तनिऽभ्यां । युवोः । श्रियं । परि । योषा । अवृणीत । सूरः । दु
हिता । परिऽतक्म्यायां । यत् । देवऽयंतं । अवथः । शचीभिः । परि । घ्रंसं । ओमना । वां । वयः । गात् । यः । ६४

हा। स्यन्। वां। रथिरा। वस्तोः। उस्राः। रथः। युजानः। परिऽयाति। वर्तिः। तेन। नः। शं। योः। उषसः। विऽउष्टौ। नि।
अश्विना। वहतं। यज्ञे। अस्मिन्। नरा। गौराऽइव। विऽश्रुतौ। तृषाणा। अस्माकं। अद्य। सवना। उप। यातं।
पुरुऽत्रा। हि। वां। मतिऽभिः। हवन्ते। मा। वां। अन्ये। नि। यमन्। देवऽयन्तः। युवं। भुज्युं। अवऽविद्धं। समुद्रे।
उत्। ऊहथुः। अर्णसः। अस्रिधानैः। पतत्रिऽभिः। अश्रमैः। अव्यथिऽभिः। दंसनाभिः। अश्विना। पा
रयन्ता। ७। १८।। आ। विश्वऽयाता। अश्विना। गतं। नः। प्र। तत्। स्थानं। अवाचि। वां। पृथिव्यां। अश्वः।
न। वाजी। शुनऽपृष्ठः। अस्थात्। आ। यत्। सेदथुः। ध्रुवसे। न। योनिं। सिसक्ति। सा। वां। सुऽमतिः।
चनिष्ठा। अतापि। घर्मः। मनुषः। दुरोणे। यः। वां। समुद्रान्। सरितः। पिपर्ति। एतऽग्वा। चित्। न।

© Dharmartha Trust J&K. Digitized by eGangotri

१ पं. सुऽयुजा । युजानः । यानि । स्थानानि । अश्विना । दधाथे इति । दिवः । यह्वीषु । ओषधीषु । विक्षु । नि । पर्वतस्य ।
६५ मूर्द्धनि । सदंता । इषं । जनाय । दाशुषे । वहंता । चनिष्ठं । देवौ । ओषधीषु । अप्ऽसु । यत् । योग्याः । अश्नवैथे इ
ति । ऋषीणां । पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि । शुश्रुऽवांसा ।
65 चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथे इति । ऋषीणां । प्रति । प्र । यातं । वरं । आ । जनाय । अस्मे इति ।
वां । अस्तु । सुऽमतिः । चनिष्ठा । यः । वां । यज्ञः । नासत्या । हविष्मान् । कृतऽब्रह्मा । सऽमर्यः । भवाति । उप ।०
। वसिष्ठं । इमा । ब्रह्माणि । ऋच्यंते । युवऽभ्यां । इयं । मनीषा । इयं । अश्विना । गीः । इमां । सुऽवृक्तिं । वृषणा ।
जुषेथां । इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । ०।।३।। अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृ ६५

© Dharmartha Trust J&K. Digitized by eGangotri

ह्मीः।अरुषाय।पथां।अश्वऽमघा।गोऽमघा।वां।हुवेम।दिवा।नक्तं।शरुं।अस्मत्।युयोतं।उपऽआयी
तं।दाशुषे।मर्त्याय।रथेन।वामं।अश्विना।वहंता।युयुतं।अस्मत्।अनिरां।अमीवां।दिवा।नक्तं।माध्वी
इति।त्रासीथां।नः।आ।वां।रथं।अवमस्यां।विऽउष्टौ।सुम्नऽयवः।वृषणः।वर्तयंतु।स्यूमऽगभस्तिं।ऋत
युक्ऽभिः।अश्वैः।आ।अश्विना।वसुऽमंतं।वहेथां।यः।वां।रथः।नृपती इति नृऽपती।अस्ति।वोढा।त्रिऽवं
धुरः।वसुऽमान्।उस्रऽयामा।आ।नः।एना।नासत्या।उप।यातं।अभि।यत्।वां।विश्वऽप्स्न्यः।जिगाति।युवं।
च्यवानं।जरसः।अमुमुक्तं।०।निः।अंहसः।तमसः।स्पर्तं।अत्रिं।नि।जाहुषं।शिथिरे।धातं।अंतरिति।०
।३०।।आ।गोऽमता।नासत्या।रथेन।अश्वऽवता।पुरुऽचंद्रेण।यातं।अभि।वां।विश्वाः।निऽयुतः।सचंते।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. स्पार्हया। श्रिया। तन्वा। शुभाना। आ। नः। देवेभिः। उप। यातं। अर्वाक्। सऽजोषसा। नासत्या। रथेन। युवोः। हि।
६६ नः। सख्या। पित्र्याणि। समानः। बंधुः। उत। तस्य। वित्तं। उत्। ऊं इति। स्तोमासः। अश्विनोः। अबुध्रन्। जामि।
ब्रह्माणि। उषसः। च। देवीः। आऽविवासन्। रोदसी इति। धिष्ण्ये इति। इमे इति। अच्छ। विप्रः। नासत्या। विवक्ति।
66 वि। च। इत्। उच्छंति। अश्विनौ। उषसः। प्र। वां। ब्रह्माणि। कारवः। भरंते।।ऽबृहत्। अग्नयः। संऽइधा। जरंते। आ।
पश्चातात्। नासत्या। आ। पुरस्तात्। आ। अश्विना। यातं। अधरात्। उदक्तात्। आ। विश्वतः। पांचऽजन्येन।
राया।।१९।। स्तोमं। देवऽयंतः। दधानाः। पुरुऽदंसा। पुरुऽतमा। पुराऽजा। अमर्त्या। हवते। अश्विना। गीः।
नि। ऊं इति। प्रियः। मनुषः। सादि। होता। नासत्या। यः। यजते। वंदते। च। अश्नीतं। मध्वः। अश्विना। उपा ६६

© Dharmartha Trust J&K. Digitized by eGangotri

के।आ।वां।यो।वै।विदथेषु।प्रयस्वान्।अहेमा।यज्ञं।पथां।उराणाः।इमां।सुऽवृक्तिं।वृषणा।जुषेथां।श्रुष्टी
वाऽइव।प्रेऽइषितः।वां।अबोधि।प्रति।स्तोमैः।जरमाणः।वसिष्ठः।उप।स्याव।वन्ही इति।गमनः।विशं।नृःऽरुक्
क्षःऽहना।संऽभृता।वीळुपाणी इति वीळुऽपाणी।सं।अंधांसि।अग्मत।मत्सराणि।मा।नः।मर्धिष्टं।आ
गतं।शिवेन।॥२॥॥दिविष्टयः।उस्राः।हुवेते।अश्विना।अयं।वां।अह्वे।अवसे।शचीवसू इति शचीऽ
वसू।विशंऽविशं।हि।गच्छथः।युवं।चित्रं।ददथुः।भोजनं।नरा।चोदेथां।सूनृताऽवते।अर्वाक्।रथं।सऽ
मनसा।नि।यच्छतं।॥आ।यातं।उप।भूषतं।मध्वः।पिबतं।अश्विना।दुग्धं।पयः।वृषणा।जेन्यावसू
इति।॥अश्व्यासः।ये।वां।उप।दाशुषः।गृहं।युवां।दीयंति।बिभ्रतः।मक्षुयुऽभिः।नरा।हयेभिः।अश्वि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ ६८

67

ना। आ। देवा। यातं। अस्मयू इत्यस्मऽयू। अधि। हा। यंतः। अश्विना। पृक्षः। सचंता। सूरयः। ना। यंसत्। नः। मघऽ
वत्ऽभ्यः। ध्रुवं। यशः। छर्दिः। अस्मभ्यं। ना। सत्या। प्र। ये। युयुः। अवृकासः। रथाःऽइव। नृऽपातारः। जना
नां। उत। स्वेन। शवसा। शूशुवुः। नरः। उत। क्षियंति। सुऽक्षितिं। ॥ २१ ॥ वि। उषाः। आवः। दिविऽजाः। ऋतेन।
आविःऽकृण्वाना। महिमानं। आ। अगात्। अप। द्रुहः। तमः। आवरित्यावः। अजुष्टं। अंगिरःऽतमा। पथ्याः। अजीग
रिति। महे। नः। अद्य। सुविताय। बोधि। उषः। महे। सौभगाय। प्र। यंधि। चित्रं। रयिं। यशसं। धेहि। अस्मे इति।
देवि। मर्तेषु। मानुषि। श्रवस्युं। एताः। त्याः। भानवः। दर्शताय। चित्राः। उषसः। अमृतासः। आ। अगुः। ज
नयंतः। दैव्यानि। व्रतानि। आऽपृणंतः। अंतरिक्षा। वि। अस्थुः। एषा। स्या। युजाना। पराकात्। पंच। क्षितीः। ६७

© Dharmartha Trust J&K. Digitized by eGangotri

परि । सद्यः । जिगाति । अभिऽपश्यंती । वयुना । जनानां । दिवः । दुहिता । भुवनस्य । पत्नी । वाजिनीऽवती । सूर्य्यस्य । योषा । चित्रऽमघा । रायः । ईशे । वसूनां । ऋषिऽस्तुता । जरयंती । मघोनी । उषाः । उच्छति । वह्निऽभिः । गृणाना । प्रति । द्युतानां । अरुषासः । अश्वाः । चित्राः । अदृश्रन् । उषसं । वहंतः । याति । शुभ्रा । विश्वऽपिशा । रथेन । दधाति । रत्नं । विधते । जनाय । सत्या । सत्येभिः । महती । महत्ऽभिः । देवी । देवेभिः । यजता । यजत्रैः । रुजत् । दृळ्हानि । ददत् । उस्रियाणां । प्रति । गावः । उषसं । वावशंत । नु । नः । गोऽमत् । वीरऽवत् । धेहि । रत्नं । उषः । अश्वऽवत् । पुरुऽभोजः । अस्मे इति । मा । नः । बर्हिः । पुरुषता । निदे । कः ॥ ७ २२ ॥ उत् । ऊं इति । ज्योतिः । अमृतं । विश्वऽजन्यं । विश्वानरः । सविता । देवः । अश्रेत् । क्रत्वा । देवानां । अजनिष्ट । चक्षुः । आविः । अ

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. कः । भुवनं । विश्वं । उषाः । प्र । मे । पंथाः । देवऽयानाः । अदृश्रन् । अमर्धंतः । वसुऽभिः । इष्कृतासः । अभूत् । ऊं इ

६८ ति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः । तानि । इत् । अहानि । बहुलानि । आ

सन् । या । प्राचीनं । उत्ऽइता । सूर्यस्य । यतः । परि । जारःऽइव । आऽचरंती । उषः । ददृक्षे । न । पुनः । यतीऽइव ।

68 ते । इत् । देवानां । सधऽमादः । आसन् । ऋतऽवानः । कवयः । पूर्व्यासः । गूळ्हं । ज्योतिः । पितरः । अनु । अविं

दन् । सत्यऽमंत्राः । अजनयन् । उषसं । समाने । ऊर्वे । अधि । संऽगतासः । सं । जानते । न । यतंते । मिथः । ते ।

ते । देवानां । न । मिनंति । व्रतानि । अमर्धंतः । वसुऽभिः । यादमानाः । प्रति । त्वा । स्तोमैः । ईळते । वसिष्ठाः ।

उषःऽबुधः । सुऽभगे । तुस्तुऽवांसः । गवां । नेत्री । वाजऽपत्नी । नः । उच्छ । उषः । सुऽजाते । प्रथमा । जरस्व । एषा । ६८

© Dharmartha Trust J&K. Digitized by eGangotri

नेत्री। राधसः। सूनृतानां। उषाः। उच्छंती। रिभ्यते। वसिष्ठैः। दीर्घऽश्रुतं। रयिं। अस्मे इति। दधाना। ७। २३। उपो
इति। रुरुचे। युवतिः। न। योषा। विश्वं। जीवं। प्रऽसुवंती। चरायै। अभूत्। अग्निः। सं॒ऽइधे। मानुषाणां। अकः।
ज्योतिः। बाधमाना। तमांसि। विश्वं। प्रतीची। सऽप्रथाः। उत्। अस्थात्। रुशत्। वासः। बिभ्रती। शुक्रं। अ
श्वैत्। हिरण्यऽवर्णा। सुदृशीकऽसंदृक्। गवां। माता। नेत्री। अह्नां। अरोचि। देवानां। चक्षुः। सुऽभगा। व
हंती। श्वेतं। नयंती। सुऽदृशीकं। अश्वं। उषाः। अदर्शि। रश्मिऽभिः। विऽअक्ता। चित्रऽमघा। विश्वं। अनु।
प्रऽभूता। अंतिऽवामा। दूरे। अमित्रं। उछ। उर्वीं। गव्यूतिं। अभयं। कृधि। नः। यवय। द्वेषः। आ। भर। वसू
नि। चोदय। राधः। गृणते। मघोनि। अस्मे इति। श्रेष्ठेभिः। वि। भाहि। उषः। देवि। प्रऽतिरंती। नः। आयुः।

भानुऽभिः।

© Dharmartha Trust J&K. Digitized by eGangotri

भिः।

११पं इषं । च । नः । दधती । विश्वऽवारे । गोऽमत् । अश्वऽवत् । रथऽवत् । च । राधः । यां । त्वा । दिवः । दुहितः । वर्धयंति ।
६९ उषः । सुऽजाते । मतिऽभिः । वसिष्ठाः । सा । अस्मासु । धाः । रयिं । ऋष्वं । बृहंतं ॥ग॥२४॥ प्रति । केतवः । प्रथमाः ।
अदृश्रन् । ऊर्ध्वाः । अस्याः । अंजयः । वि । श्रयंते । उषः । अर्वाचा । बृहता । रथेन । ज्योतिष्मता । वामं । अस्मभ्यं ।
69
वक्षि । प्रति । सीं । अग्निः । जरते । संऽइद्धः । प्रति । विप्रासः । मतिऽभिः । गृणंतः । उषाः । याति । ज्योतिषा । बा
धमाना । विश्वा । तमांसि । दुःऽइता । अप । देवी । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छंती । उषसः । वि
न ऽभातीः । अजीजनन् । सूर्यं । यज्ञं । अग्निं । अपाचीनं । तमः । अगात् । अजुष्टं । अचेति । दिवः । दुहिता । म
घोनी । विश्वं । पश्यंति । उषसं । विऽभातीं । स्वधया । युज्यमानं । आ । यं । अश्वासः । सुऽयुजः । वहंति । ६९

© Dharmartha Trust J&K. Digitized by eGangotri

प्रति। त्वा। अथ। सुऽमनसः। बुधंत। अस्माकासः। मघऽवानः। वयं। च। तिल्विलायध्वं। उषसः। विऽभातीः।१०
।।२५।। प्र। पथ्या। जनानां। पंच। क्षितीः। मानुषीः। बोधयंती। सुसंदृक्ऽभिः। उक्षऽभिः। भानुं। अश्रेत्। वि। स्तृ
र्यैः। रोदसी इति। चक्षसा। आ। वरिस्यो। वः। वि। अंजते। दिवः। अंतेषु। अक्तून्। विशः। न। युक्ताः। उषसः। यतंते।
सं। ते। गावः। तमः। आ। वर्तयंति। ज्योतिः। यच्छंति। सविताऽइव। बाहू इति। अभूत्। उषाः। इंद्रऽतमा। मघो
नी। अजीजनत्। सुविताय। श्रवांसि। वि। दिवः। देवी। दुहिता। दधाति। अंगिरःऽतमा। सुऽकृते। वसूनि।
तावत्। उषः। राधः। अस्मभ्यं। रास्व। यावत्। स्तोतृऽभ्यः। अरदः। गृणाना। यां। त्वा। जज्ञुः। वृषभस्य। रवे
ण। वि। दृळ्हस्य। दुरः। अद्रेः। और्णोः। देवंऽदेवं। राधसे। चोदयंती। अस्मद्र्यक्। सूनृताः। ईरयंती। वि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. उछंतीं।नः।स्तनयें।।धियंः।धाः।।७।।२६।।प्रति।स्तोमेभिः।उषसं।वसिष्ठाः।गीःऽभिः।विप्रासः।प्रथमाः।अबुध्र

७० न्।विवर्तयंतीं।रजसी इति।समंते इति संऽअंते।आविःऽकृण्वतीं।भुवनानि।विश्वा।एषा।स्या।नव्यं।आ

70 युः।दधाना।गूढ्वी।तमः।ज्योतिषा।उषाः।अबोधि।अग्नेः।एति।युवतिः।अह्याणा।प्र।अचिकितत्।सूर्यं

यज्ञं।अग्निं।।७।।२७।।इति पंचमाष्टके पंचमोध्यायः।। ।।ओं मा प्रस्तु षट्ऽगाथमिंद्रा वसण्णादशैंद्रावरु

णं हरणा गते तु युगे नरा वा पंचपुनीषधी रा षष्ठो वारुणं हर त्वस्य प्र प्र भुं ध्रुवमं स्या पाशविमोचनी सोषु पंच गा

यत्र जगत्यं तं प्रवीर या सप्त नाय व्यंस्थे स्त्र्यंध्यु आभ्य व्या हि वकुम्भाः कुविदं गाथा यो पंच शुचि न्व ष्टा वै द्वाग्नेत्वि यंवा

ह्वादशा गायत्र मंत्या नुष्टुप् प्र क्षोद सा षट् सारस्वते तु तृतीया सरस्वते वृहदुप्र गाथः प्रस्तार पंक्तिः परास्ति ७०

© Dharmartha Trust J&K. Digitized by eGangotri

स्तोगायत्र्यः सरस्वतेयज्ञेदशौंग्याद्दिवाहस्पस्पमंस्यैंद्रींवंतन्नीयानयम्यावैंद्राब्राह्मणस्यस्येअध्वर्यवः सत्ता

क्रुदेवतांत्यांपरोवैछबंनूत्नमिसैंघश्ववतिस्तोनूमतः।। ।।ओंम्।।प्रति।ऊं इति। अदर्शि। आऽयती। उ हं

नी। दुहिता। दिवः। अपो इति। महि। व्ययति। चक्षसे। तमः। ज्योतिः। कृणोति। सूनरी। उत्। उस्त्रियाः। सृजते।

सूर्यः। सचा। उत्ऽयत्। नक्षत्रं। अर्चिऽवत्। तव। इत्। उषः। विऽउषि। सूर्यस्य। च। सं। भक्तेन। गमेम। ॥ प्रति। हृ

त्वा। दुहितः। दिवः। उषः। जीराः। अभुत्स्महि। या। वहसि। पुरु। स्पार्हं। वनन्ऽवति। रत्नं। न। दाशुषे। मयः। उ हं

नीया। कृणोषि। मंहना। महि। प्रऽख्यै। देवि। स्वः। दृशे। तस्याः। ते। रत्नऽभाजः। ईमहे। वयं। स्याम। मातुः।

न। सूनवः। तत्। चित्रं। राधः। आ। भर। उषः। यत्। ते। दीर्घश्रुत्ऽतमं। यत्। ते। दिवः। दुहितः। मर्तऽभोजनं। तत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. रास्वा। भुनज्मा। मैहै। श्रवः। सूरिऽभ्यः। अमर्ता। वसुऽत्वनं। वाजाना। अस्मभ्यं। गोऽमतः। चोदयित्री। मघोनः।
७१ सूनृताऽवती। उषाः। उछत्। अप। स्त्रिधः।१। इंद्रावरुणा। युवं। अध्वराय। नः। विशे। जनाय। महि। शर्म।
यछतं। दीर्घऽप्रयज्युं। अति। यः। वनुष्यति। वयं। जयेम। पृतनासु। दुःऽध्यः। संऽराट्। अन्यः। स्वऽराट्। अ
न्यः। उच्यते। वां। महांतौ। इंद्रावरुणा। महावसू इति महाऽवसू। विश्वे। देवासः। परमे। विऽओमनि। सं
वां। ओजः। वृषणा। सं। बलं। दधुः। अपां। अनु। खानि। अतृंतं। ओजसा। आ। सूर्यं। ऐरयतं। दिवि। प्रऽ
भुं। इंद्रावरुणा। मदे। अस्य। मायिनः। अपिन्वतं। अपितः। पिन्वतं। धियः। युवां। इत्था। युत्ऽसु। पृतना
सु। वह्नयः। युवां। क्षेमस्य। प्रऽसवे। मितऽज्ञवः। ईशाना। वस्वः। उभयस्य। कारवः। इंद्रावरुणा। सुऽहवा। ७३

71

© Dharmartha Trust J&K. Digitized by eGangotri

हवामहे । इन्द्रावरुणा । यत् । इमानि । चक्रथुः । विश्वा । जातानि । भुवनस्य । मज्मना । क्षेमेण । मित्रः । वरुणं । दु-
वस्यति । मरुत्ऽभिः । उग्रः । शुभं । अन्यः । ईयते ॥ ५ ॥ महे । शुल्काय । वरुणस्य । नु । त्विषे । ओजः । मिमाते । इ-
ति । ध्रुवं । अस्य । यत् । स्वं । अजामिं । अन्यः । श्नथयन्तं । आ । अतिरत् । दभ्रेभिः । अन्यः । प्र । वृणोति । भूय-
सः । ६ । दुःऽइतानि । मर्त्यं । इन्द्रावरुणा । न । तपः । कुतः । चन । यस्य । देवा । गच्छथः । वीथः । अध्वरं । न । तं । मर्त्त-
स्य । नशते । परिऽह्वृतिः । अर्वाक् । नरा । दैव्येन । अवसा । आ । गतं । शृणुतं । हवं । यदि । मे । जुजोषथः । युवोः
। हि । सख्यं । उत । वा । यत् । आप्यं । मार्डीकं । इन्द्रावरुणा । नि । यच्छतं । अस्माकं । इन्द्रावरुणा । भरेऽभरे । पु-
रःऽयोधा । भवतं । कृष्टिऽओजसा । यत् । वां । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पे. सातिषु। अस्मे इति। इन्द्रः। वरुणः। मित्रः। अर्यमा। द्युम्नं। यच्छन्तु। महि। शर्म। सऽप्रथः। अवध्रं। ज्योतिः। अ

७२ दितेः। ऋतऽवृधः। देवस्य। श्लोकं। सवितुः। मनामहे। ३। युवां। नरा। पश्यमानासः। आप्यं। प्राचा। गव्य

न्तः। पृथुऽपर्शवः। ययुः। दासा। च। वृत्रा। हतं। आर्याणि। च। सुऽदासं। इन्द्रावरुणा। अवसा। अवतं। यत्र।

नरः। संऽअयन्ते। कृतऽध्वजः। यस्मिन्। आजा। भवति। किं। चन। प्रियं। यत्र। भयन्ते। भुवना। स्वःऽदृशः।

रु तत्र। नः। इन्द्रावरुणा। अधि। वोचतं। सं। भूम्याः। अन्ताः। ध्वसिराः। अदृक्षत। इन्द्रावरुणा। दिवि। घोषः। आ।

अरुहत्। अस्थुः। जनानां। उप। मां। अरातयः। अर्वाक्। आ। अवसा। हवनऽश्रुता। आ। गतं। इन्द्रावरुणा। व वे

धनाभिः। अप्रति। भेदं। वन्वन्ता। प्र। सुऽदासं। आवतं। ब्रह्माणि। एषां। शृणुतं। हवीमनि। सत्या। तृत्सू ७२

© Dharmartha Trust J&K. Digitized by eGangotri

नो। अभुवत्। पुरःऽहितिः। इंद्रावरुणौ। अभि। आ। तपंति। मा। अघानि। अर्यः। वनुषां। अरातयः। युवं। हि।
वस्वः। उभयस्य। राजथः। अध। स्म। नः। अवतं। पार्ये। दिवि॥ ५॥ युवां। हवंते। उभयासः। आजिषु। इंद्रा। च। व
स्वः। वरुणा। च। सातये। यत्र। राजऽभिः। दशऽभिः। निऽबाधितं। प्र। सुऽदासं। आवतं। तृत्सुऽभिः। सह। दश।
राजानः। संऽइताः। अयज्यवः। सुऽदासं। इंद्रावरुणा। न। युयुधुः। सत्या। नृणां। अद्मऽसदां। उपऽस्तुतिः।
देवाः। एषां। अभवन्। देवऽहूतिषु। दाशऽराज्ञे। परिऽयत्ताय। विश्वतः। सुऽदासं। इंद्रावरुणौ। अशिक्षतं।
श्वित्यंचः। यत्र। नमसा। कपर्दिनः। धिया। धीवंतः। असपंत। तृत्सवः। वृत्राणि। अन्यः। संऽइथेषु। जिघ्न
ते। व्रतानि। अन्यः। अभि। रक्षते। सदा। हवामहे। वां। वृषणा। सुवृक्तिऽभिः। अस्मेऽइति। इंद्रावरुणा। शर्म।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. यरुसं।ग।५।आ।वां।राजानौ।अध्वरे।ववृत्यां।हव्येभिः।इंद्रावरुणा।नमःऽभिः।प्र।वां।घृताची।बाह्वोः।दधाना।
७३ परि।त्मना।विषुःऽरूपा।जिगाति।युवोः।राष्ट्रं।बृहत्।इन्वति।द्यौः।यौ।सेतृऽभिः।अरज्जुऽभिः।सिनीथः।परि।
नः।हेळः।वरुणस्य।वृज्याः।उरुं।नः।इंद्रः।कृणवत्।ऊं इति।लोकं।कृतं।नः।यज्ञं।विदथेषु।चारुं।कृतं।ब्रह्मा
73 णि।सूरिषु।प्रऽशस्ता।उपो इति।रयिः।देवऽजूतः।एतु।प्र।नः।स्पार्हाभिः।ऊतिऽभिः।तिरेतं।अस्मे इति।इंद्रा नः।
वरुणा।विश्वऽवारं।रयिं।धत्तं।वसुऽमंतं।पुरुऽक्षुं।प्र।यः।आदित्यः।अनृता।मिनाति।अमिता।शूरः।द
यते।वसूनि।इयं।इंद्रं।वरुणं।अष्ट।मे।गीः।प्र।आवत्।तोके।तनये।तूतुजाना।सुऽरत्नासः।देवऽवीतिं।
गमेम।बाद्धा।पुनीषे।वां।अरक्षसं।मनीषां।सोमं।इंद्राय।वरुणाय।जुह्वत्।घृतऽप्रतीकां।उषसं।न। ७३

© Dharmartha Trust J&K. Digitized by eGangotri

देवीं।ता।नः।यामन्।उरुष्यतां।अभीके।स्पर्धंते।वै।ऊं इति।देवऽहूये।अत्र।येषु।ध्वजेषु।दिद्यवः।पतंति।यु
वं।तान्।इंद्रावरुणौ।अमित्रान्।हतं।पराचः।शर्वा।विषूचः।आपः।चित्।हि।स्वऽयशसः।सदःऽसु।देवीः।
इंद्रं।वरुणं।देवता।धुरिति धुः।कृष्टीः।अन्यः।धारयति।प्रऽविक्ताः।वृत्राणि।अन्यः।अप्रतीनि।हंति।सः।
सुऽक्रतुः।ऋतऽचित्।अस्तु।होता।यः।आदित्या।शवसा।वां।नमस्वान्।आऽववर्तत्।अवसे।वां।हवि
ष्मान्।असत्।इत्।सः।सुविताय।प्रयस्वान्।४।७।धीरा।तु।अस्य।महिना।जनूंषि।वि।यः।तस्तं
भ।रोदसी इति।चित्।उर्वी इति।प्र।नाकं।ऋष्वं।नुनुदे।बृहंतं।द्विता।नक्षत्रं।पप्रथत्।च।भूम।उत।स्व
या।तन्वा।सं।वदे।तत्।कदा।नु।अंतः।वरुणे।भुवानि।किं।मे।हव्यं।अहृणानः।जुषेत।कदा।मृळी

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. के। सुऽमनाः। अभि। ख्यं। प्रष्टो। तत्। एनः। वरुण। दिदृक्षु। उपो। इति। एमि। चिकितुषः। विऽपृच्छं। समानं। इत्।
७४ मे। कवयः। चित्। आहुः। अयं। ह। तुभ्यं। वरुणः। हृणीते। किं। आगः। आस। वरुण। ज्येष्ठं। यत्। स्तोतारं। जि
घांससि। सखायं। प्र। तत्। मे। वोचः। दुःऽदभ। स्वधाऽवः। अव। त्वा। अनेनाः। नमसा। तुरः। इयां। अव।
द्रुग्धानि। पित्र्या। सृज। नः। अव। या। वयं। चकृम। तनूभिः। अव। राजन्। पशुऽतृपं। न। तायुं। सृज। वत्सं।
न। दाम्नः। वसिष्ठं। न। सः। स्वः। दक्षः। वरुण। ध्रुतिः। सा। सुरा। मन्युः। विऽभीदकः। अचित्तिः। अस्ति। ज्या
यान्। कनीयसः। उपऽअरे। स्वप्नः। चन। इत्। अनृतस्य। प्रऽयोता। अरं। दासः। मीळ्हुषे। कराणि। अहं। न।
देवाय। भूर्णये। अनागाः। अचेतयत्। अचितः। देवः। अर्यः। गृत्सं। राये। कविऽतरः। जुनाति। अयं। सु। ७४

74

© Dharmartha Trust J&K. Digitized by eGangotri

तुभ्यं।वरुण।स्वधाऽवः।हृदि।स्तोमः।उपऽश्रितः।चित्।अस्तु।शं।नः।क्षेमे।शं।ऊं इति।योगे।नः।अस्तु।८।।२।।

रदत्।पथः।वरुणः।सूर्याय।प्र।अर्णांसि।समुद्रिया।नदीनां।सर्गः।न।सृष्टः।अर्वतीः।ऋतऽयन्।चकार।

मुहीः।अवनीः।अहऽभ्यः।आत्मा।ते।वातः।रजः।आ।नवीनोत्।पशुः।न।भूर्णिः।यवसे।ससऽवान्।अंतः।

मही इति।बृहती इति।रोदसी इति।इमे इति।विश्वा।ते।धाम।वरुण।प्रियाणि।परि।स्पशः।वरुणस्य।स्म

त्ऽदिष्टाः।उभे इति।पश्यंति।रोदसी इति।सुमेके इति सुऽमेके।ऋतऽवानः।कवयः।यज्ञऽधीराः।प्रऽचेतसः।

ये।इषयंत।मन्म।उवाच।मे।वरुणः।मेधिराय।त्रिः।सप्त।नाम।अघ्न्या।बिभर्ति।विद्वान्।पदस्य।गुह्या।

न।वोचत्।युगाय।विप्रः।उपराय।शिक्षन्।तिस्रः।द्यावः।निऽहिताः।अंतः।अस्मिन्।तिस्रः।भूमीः।उप

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. राः। षट्ऽविधानाः। गृत्सः। राजा। वरुणः। चक्रे। एतं। दिवि। प्रऽईङ्खं। हिरण्ययं। शुभे। कं। अव। सिंधुं। वरुणः।
७५ द्यौःऽइव। स्थात्। द्रप्सः। न। श्वेतः। मृगः। तुविष्मान्। गंभीरऽशंसः। रजसः। विऽमानः। सुपारऽक्षत्रः। स
75 तः। अस्य। राजा। यः। मृळयाति। चक्रुषे। चित्। आगः। वयं। स्याम। वरुणे। अनागाः। अनु। व्रतानि। अदि
तेः। ऋधंतः। ०। ०। प्र। शुंध्युवं। वरुणाय। प्रेष्ठां। मतिं। वसिष्ठ। मीळ्हुषे। भरस्व। यः। ईं। अर्वांचं। करते।
यजत्रं। सहस्रऽमघं। वृषणं। बृहंतं। अध। नु। अस्य। संऽदृशं। जगन्वान्। अग्नेः। अनीकं। वरुणस्य। मं
सि। स्वः। यत्। अश्मन्। अधिऽपाः। ऊं इति। अंधः। अभि। मा। वपुः। दृशये। निनीयात्। आ। यत्। रुहा
व। वरुणः। च। नावं। प्र। यत्। समुद्रं। ईरयाव। मध्यं। अधि। यत्। अपां। स्नुऽभिः। चराव। प्र। प्रऽईङ्खे। ७५

© Dharmartha Trust J&K. Digitized by eGangotri

ईङ्खयावहै। शुभे। कं। वसिष्ठं। ह। वरुणः। नावि। आ। अधात्। ऋषिं। चकार। सुऽअपाः। महःऽभिः। स्तोतारं। वि
प्रः। सुदिनऽत्वे। अह्नां। यात्। नु। द्यावः। ततनन्। यात्। उषसः। कं। यानि। नौ। सख्या। बभूवुः। सचा। वहे। इति
ऽवत्। अवृकं। पुरा। चित्। बृहन्तं। मानं। वरुण। स्वधाऽवः। सहस्रऽद्वारं। जगम। गृहं। ते। यः। आपिः। नित्यः। व
रुण। प्रियः। सन्। त्वां। आगांसि। कृणवत्। सखा। ते। मा। ते। एनस्वन्तः। यक्षिन्। भुजेम। यन्धि। स्म। विप्रः।
स्तुवते। वरूथं। ध्रुवासु। त्वा। आसु। क्षितिषु। क्षियन्तः। वि। अस्मत्। पाशं। वरुणः। मुमोचत्। अवः। वन्वा
नाः। अदितेः। उपऽस्थात्। ॥ १० ॥ मो इति। सु। वरुण। मृत्ऽमयं। गृहं। राजन्। अहं। गमं। मृळ। सुऽक्षत्र। मृ
ळय। यत्। एमि। प्रस्फुरन्ऽइव। दृतिः। न। ध्मातः। अद्रिऽवः। ॥ क्रत्वः। समह। दीनता। प्रतिऽईपं। जगम।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. शुचे॥०॥अपां।मध्ये।तस्थिऽवांसं।तृष्णा।अविदत्।जरितारं॥०॥यत्।किं।च।इदं।वरुण।दैव्ये।जने।अभिऽद्रो
७६ हं।मनुष्याः।चरामसि।अचित्ती।यत्।तव।धर्म।युयोपिम।मा।नः।तस्मात्।एनसः।देव।रीरिषः॥१४॥
प्रऽवीरऽया।शुचयः।दद्रिरे।वां।अध्वर्युऽभिः।मधुऽमन्तः।सुतासः।वह।वायो इति।निऽयुतः।याहि।अ
76 च्छ।पिब।सुतस्य।अन्धसः।मदाय।ईशानाय।प्रऽहुतिं।यः।ते।आनट्।शुचिं।सोमं।शुचिऽपाः।तुभ्यं।वा
यो इति।कृणोषि।तं।मर्त्येषु।प्रऽशस्तं।जातःऽजातः।जायते।वाजी।अस्य।राये।अनु।यं।जज्ञतुः।रोदसी इ
ति।इमे इति।राये।देवी।धिषणा।धाति।देवं।अध।वायुं।निऽयुतः।सश्चत।स्वाः।उत।श्वेतं।वसुऽधितिं।
निरेके।उच्छन्ताः।उषसः।सुऽदिनाः।अरिप्राः।उरु।ज्योतिः।विविदुः।दीध्यानाः।गव्यं।चित्।ऊर्वं।उशिजः। ७६

© Dharmartha Trust J&K. Digitized by eGangotri

त्रिाव्रुतुः। तेषां। अनु। प्रऽदिवः। सस्रुः। आपः। ते। स्तुसे। नाम। नसा। दीध्यानाः। स्वेन। युक्तासः। क्रतुना। वहंति। इं
द्रवायू इति। वीरऽवाहं। रथं। यां। ईशानयोः। अभि। पृक्षः। सचंते। ईशानासः। ये। दधते। स्वः। नः। गोभिः। अश्वे
भिः। वसुऽभिः। हिरण्यैः। इंद्रवायू इति। सूरयः। विश्वं। आयुः। अर्वत्ऽभिः। वीरैः। पृतनासु। सस्रुः। अर्वंतः। न। अश्र न
वसः। भिक्षमाणाः। इंद्रवायू इति। सुस्तुतिऽभिः। वसिष्ठाः। वाजऽयंतः। सु। अवसे। हुवेम। ॥ ३ ॥ कुवित्। अं
ग। नमसा। ये। वृधासः। पुरा। देवाः। अनवद्यासः। आसन्। ते। वायवे। मनवे। बाधिताय। अवासयन्।
उषसं। सूर्येण। उशंतः। दूताः। न। अदमाय। गोपाः। मा। स्तः। च। पाथः। शरदः। च। पूर्वीः। इंद्रवायू इति। सुस्तुतिः। स्तु
वां। इयाना। मार्डीकं। ईट्टे। सुवितं। च। नव्यं। पीवःऽअन्नान्। रयिऽवृधः। सुऽमेधाः। श्वेतः। सिसक्ति। नि।

© Dharmartha Trust J&K. Digitized by eGangotri

१.वं. सुतां। अभिऽश्रीः। तेः। वायवे। सऽमनसः। वि। तस्थुः। विश्वाः। इत्। नरः। सुऽअपत्यानि। चक्रुः। या
७७ वत्। तरः। तन्वः। यावत्। ओजः। यावत्। नरः। चक्षसा। दीध्यानाः। शुचिं। सोमं। शुचिऽपा। पातं। अस्मे
इति। इंद्रवायू इति। सदतं। बर्हिः। आ। इदं। नियुत्वान्। नियुत्वन्तः। स्पार्हऽवीराः। इंद्रवायू इति। सऽरथं। या
तं। अर्वाक्। आ। इदं। हि। वां। प्रऽभृतं। मध्वः। अग्रं। अध। प्रीणाना। वि। मुमुक्तं। अस्मे इति। याः। वां। शतं। नि
ऽयुतः। याः। सहस्रं। इंद्रवायू इति। विश्वऽवाराः। सचंते। आ। आभिः। यातं। सुऽविदत्राभिः। अर्वाक्। पा
ति तं। नरा। प्रतिऽभृतस्य। मध्वः। ग। ३॥ आ। वायो इति। भूष। शुचिऽपाः। उप। नः। सहस्रं। ते। निऽयुतः। विश्व
ऽवार। उपो इति। ते। अंधः। मद्यं। अयामि। यस्य। देव। दधिषे। पूर्वऽपेयं। प्र। सोता। जीरः। अध्वरेषु। अ ७७

© Dharmartha Trust J&K. Digitized by eGangotri

स्थाल्।सोमं।इंद्राय।वायवे।पिबध्यै।प्र।यन्ता।वां।मध्वः।अग्रियं।भरंति।अध्वर्यवः।देवऽयंतः।शचीभिः
।प्रयाभिः।या।सि।दाश्वांसं।अच्छ।नियुत्ऽभिः।वायो इति।इष्टये।दुरोणे।नि।नः।रयिं।सुऽभोजसं।यु
वस्व।नि।वीरं।गव्यं।अश्व्यं।च।राधः।ये।वायवे।इंद्रऽमादनासः।आऽदेवासः।निःऽतोशनासः।अर्यः।घ्न
तः।वृत्राणि।सूरिऽभिः।स्याम।सासह्वांसः।युधा।नृऽभिः।अमित्रान्।०।वायो इति।अस्मिन्।सवने।
मादयस्व।०।।१५।शुचिं।नु।स्तोमं।नवऽजातं।अद्य।इंद्राग्नी इति।वृत्रऽहना।जुषेथां।उभा।हि।वां।सुऽ
हवा।जोहवीमि।ता।वाजं।सद्यः।उशते।धेष्ठा।ता।सानसी इति।शवसाना।हि।भूतं।साकंऽवृधा।श
वसा।शूशुऽवांसा।क्षयंतौ।रायः।यवसस्य।भूरेः।पृक्तं।वाजस्य।स्थविरस्य।घृष्वेः।उपो इति।ह।य्

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. ता।विदथे।वाजिनः।गुः।धीभिः।विप्राः।प्रऽमतिं।इछमानाः।अर्वंतः।न।काष्ठां।नक्षमाणाः।इंद्राग्नी इति।जो
७८ हुवतः।नरः।ता।गीःऽभिः।विप्रः।प्रऽमतिं।इछमानः।ईट्टे।रयिं।यशसं।पूर्वऽभाजं।इंद्राग्नी इति।वृत्रऽहना।
78 सुऽवज्रा।प्रत्ना।नव्येभिः।तिरतं।देष्णैः।सा।यत्।मही इति।मिथती इति।स्वर्दमाने इति।तुन्नऽरुचा।भरः
साता।यतैते इति।अदेवऽयुं।विदथे।देवयुऽभिः।सत्रा।हतं।सोमऽसुता।जनेन॥२५॥इमां।ऊं इति।सु।सो
मऽसुतिं।उप।नः।आ।इंद्राग्नी इति।सौमनसाय।यातं।नु।चित्।हि।परिमम्नाथे इति परिऽमम्नाथे।अ
स्मान्।आ।वां।शश्वत्ऽभिः।ववृतीय।वाजैः।सः।अग्ने।एना।नमसा।संऽइद्धः।अछ।मित्रं।वरुणं।इंद्रं।
वोचेः।गमरऽकान।तत्।अर्यमा।अदितिः।शिश्रथंतु।एताः।अग्ने।आशुषाणाः।सः।इष्टीः।युवोः।सचा।अ ७८
यत्सीमागश्चकृमातत्सु

© Dharmartha Trust J&K. Digitized by eGangotri

भि। अश्याम। वाजान्। आ। इंद्रः। नः। विष्णुः। मरुतः। परि। ख्यन्। ।०।१८। इयं। वां। अस्य। मन्मनः। इंद्रा

ग्नी इति। पूर्व्यऽस्तुतिः। अभ्रात्। वृष्टिःऽइव। अजनि। शृणुतं। जरितुः। हवं। इंद्राग्नी इति। वनतं। गिरः। ई

शाना। पिप्यतं। धियः। मा। पापऽत्वाय। नः। नरा। इंद्राग्नी इति। मा। अभिऽशस्तये। मा। नः। रीरधतं।

निदे। इंद्रे। अग्ना। नमः। बृहत्। सुऽवृक्तिं। आ। ईरयामहे। धिया। धेनाः। अवस्यवः। ता। हि। शश्वंतः।

ईळते। इत्था। विप्रासः। ऊतये। सऽबाधः। वाजऽसातये। ता। वां। गीःऽभिः। विपन्यवः। प्रयस्वंतः। हवामहे। मेधऽ

साता। सनिष्यवः। १७। इंद्राग्नी इति। अवसा। आ। गतं। अस्मभ्यं। चर्षणिऽसहा। ०मा। कस्य। नः। ०। गोऽम

त्। हिरण्यऽवत्। वसु। यत्। वां। अश्वऽवत्। ईमहे। इंद्राग्नी इति। तत्। वनेम। हि। यत्। सोमे। आ। सुते। नरः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. इंद्राग्नी इति । अजोहवुः । सप्तिऽवंता । सपर्यवः । उक्थेभिः । वृत्रहन्ऽतमा । या । मंदाना । चित् । आ । गिरा । आंगू-
७९ षैः । आऽविवासतः । तौ । इत् । दुःऽशंसं । मर्त्यं । दुःऽविद्वांसं । रक्षस्विनं । आऽभोगं । हन्मना । हतं । उदऽधिं । हन्मना ।
हतं ॥ ३ ॥ प्र । क्षोदसा । धायसा । सस्रे । एषा । सरस्वती । धरुणं । आयसी । पूः । प्रऽबाबधाना । रथ्याऽइव । या-
79 ति । विश्वाः । अपः । महिना । सिंधुः । अन्याः ॥ एका । अचेतत् । सरस्वती । नदीनां । शुचिः । यती । गिरिऽभ्यः । आ ।
समुद्रात् । रायः । चेतंती । भुवनस्य । भूरेः । घृतं । पयः । दुदुहे । नाहुषाय ॥ सः । ववृधे । नर्यः । योषणासु ।
वृषा । शिशुः । वृषभः । यज्ञियासु । सः । वाजिनं । मघवत्ऽभ्यः । दधाति । वि । सातये । तन्वं । ममृजीत । उ-
त । स्या । नः । सरस्वती । जुषाणा । उप । श्रवत् । सुऽभगा । यज्ञे । अस्मिन् । मितज्ञुऽभिः । नमस्यैः । इयाना । ७९

© Dharmartha Trust J&K. Digitized by eGangotri

राया।युजा।चित्।उत्ऽतरा।सखिऽभ्यः।इमा।जुह्वाना।युष्मत्।आ।नमःऽभिः।प्रति।स्तोमं।सरस्व
ति।जुषस्व।तव।शर्मन्।प्रियऽतमे।दधानाः।उप।स्थेयाम।शरणं।न।वृक्षं।अयं।ऊं इति।ते।सरस्वति।
वसिष्ठः।द्वारौ।ऋतस्य।सुऽभगे।वि।आवरिस्यावः।वर्ध।शुभ्रे।स्तुवते।रासि।वाजान्।ग।१०।बृहत्।ऊं इ
ति।गाय।इषा।वचः।असुर्या।नदीनां।सरस्वतीं।इत्।महय।सुवृक्तिऽभिः।स्तोमैः।वसिष्ठ।रोदसी इति

ते उभे इति।यत्।ते।महिना।शुभ्रे।[illegible]।अंधसी इति।अधिऽक्षियंति।पूरवः।सा।नः।बोधि।अवित्री।मरुत्ऽ
सखा।चोद।राधः।मघोनां।भद्रं।इत्।भद्रा।कृणवत्।सरस्वती।अकवऽअरी।चेतति।वाजिनीऽवती।
गृणाना।जमदग्निऽवत्।स्तुवाना।च।वसिष्ठऽवत्।जनिऽयंतः।नु।अग्रवः।पुत्रिऽयंतः।सुऽदानवः।स

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. रस्वंतं। हवामहे। यः। ते। सरस्वः। ऊर्मयः। मधुऽमंतः। घृतऽश्चुतः। तेभिः। नः। अविता। भव। पीपिऽवांसं। सर
८० स्वतः। स्तनं। यः। विश्वऽदर्शतः। भक्षीमहि। प्रऽजां। इषं। २०॥ यज्ञे। दिवः। नृऽसदने। पृथिव्याः। नरः। यत्र। दे
वऽयवः। मदंति। इंद्राय। यत्र। सवनानि। सुन्वे। गमत्। मदाय। प्रथमं। वयः। च। आ। दैव्या। वृणीमहे। अवांसि।
बृहस्पतिः। नः। महे। आ। सखायः। यथा। भवेम। मीळ्हुषे। अनागाः। यः। नः। दाता। पराऽवतः। पिताऽइ
व। तं। ऊं इति। ज्येष्ठं। नमसा। हविःऽभिः। सुऽशेवं। ब्रह्मणः। पतिं। गृणीषे। इंद्रं। श्लोकः। महि। दैव्यः। सिस
क्तु। यः। ब्रह्मणः। देवऽकृतस्य। राजा। सः। आ। नः। योनिं। सदतु। प्रेष्ठः। बृहस्पतिः। विश्वऽवारः। यः। अ
स्ति। कामः। रायः। सुऽवीर्यस्य। तं। दात्। पर्षत्। नः। अति। सश्चतः। अरिष्टान्। तं। आ। नः। अर्कं। अमृता ८०

या । जुष्टं । इमे । धासुः । अमृतासः । पुराऽजाः । शुचिऽक्रंदं । यजतं । पस्त्यानां । बृहस्पतिं । अनर्वाणं । हुवेम ॥ २१ ॥
तं । शग्मासः । अरुषासः । अश्वाः । बृहस्पतिं । सहऽवाहः । वहंति । सहः । चित् । यस्य । नीलऽवत् । सधऽस्थं ।
नभः । न । रूपं । अरुषं । वसानाः ॥ सः । हि । शुचिः । शतऽपत्रः । सः । शुंध्युः । हिरण्यऽवाशीः । इषिरः । स्वःऽसाः । बृ
हस्पतिः । सः । सुऽआवेशः । ऋष्वः । पुरु । सखिऽभ्यः । आऽसुतिं । करिष्ठः ॥ देवी इति । देवस्य । रोदसी इति । जनि
त्री इति । बृहस्पतिं । ववर्धतुः । महिऽत्वा । दक्षाय्याय । दक्षत । सखायः । करत् । ब्रह्मणे । सुऽतरा । सुऽगाधा ।
इयं । वां । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इंद्राय । वज्रिणे । अकारि ॥ ० ॥ बृहस्पते । युवं । इंद्रः । च । वस्वः । दिव्यस्य ।
ईशाथे इति । उत । पार्थिवस्य । धत्तं । रयिं । स्तुवते । कीरये । चित् ॥ ० ॥ २२ ॥ अध्वर्यवः । अरुणं । दुग्धं । अंशुं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ जुहोत।न।वृषभाय।क्षितीनां।गौः।न।वेदीयान्।अवः।पानं।इंद्रः।विश्वाहा।इत्।याति।सुतऽसोमं।इछ
८३ न्।यत्।दधिषे।प्रऽदिवि।चारु।अन्नं।दिवेऽदिवे।पीतिं।इत्।अस्य।वक्षि।उत।हृदा।उत।मनसा।जुषा
णः।उशन्।इंद्र।प्रऽस्थितान्।पाहि।सोमान्।जज्ञानः।सोमं।सहसे।पपाथ।प्र।ते।माता।महिमानं।उ
81 वाच।आ।इंद्र।पप्राथ।उरु।अंतरिक्षं।युधा।देवेभ्यः।वरिवः।चकर्थ।यत्।योधयाः।महतः।मन्यमाना
न्।साक्षाम।तान्।बाहुऽभिः।शाशदानान्।यत्।वा।नृऽभिः।वृतः।इंद्र।अभिऽयुध्याः।तं।त्वया।आजिं।
सौश्रवसं।जयेम।प्र।इंद्रस्य।वोचं।प्रथमा।कृतानि।प्र।नूतना।मघऽवा।या।चकार।यदा।इत्।अदेवीः
।असहिष्ट।मायाः।अथ।अभवत्।केवलः।सोमः।अस्य।तव।इदं।विश्वं।अभितः।पशव्यं।यत्।प ८३

© Dharmartha Trust J&K. Digitized by eGangotri

श्यसि। चक्षसा। सूर्यस्य। गवां। असि। गोऽपतिः। एकः। इंद्र। भक्षीमहि। ते। प्रऽयतस्य। वस्वः॥ ६॥ २३॥ परः। मात्रया।
जं तन्वा। वृधान। न। ते। महिऽत्वं। अनु। अश्नुवंति। उभे इति। ते। विद्म। रजसी इति। पृथिव्याः। विष्णो इति। देव। त्वं। परम
स्य। वित्से। न। ते। विष्णो इति। जायमानः। न। जातः। देव। महिम्नः। परं। अंतं। आप। उत्। अस्तभ्नाः। नाकं। ऋष्वं।
बृहंतं। दाधर्थ। प्राचीं। ककुभं। पृथिव्याः॥ इरावती इतीराऽवती। धेनुमती इति धेनुऽमती। हि। भूतं। सुयवसि
नी इति सुऽयवसिनी। मनुषे। दशस्या। वि। अस्तभ्नाः। रोदसी इति। विष्णो इति। एते इति। दाधर्थ। पृथिवीं। अ
भितः। मयूखैः॥ उरुं। यज्ञाय। चक्रथुः। ऊं इति। लोकं। जनयंता। सूर्यं। उषसं। अग्निं। दासस्य। चित्। वृषऽशिप्रस्य।
मायाः। जघ्नथुः। नरा। पृतनाज्येषु॥ इंद्राविष्णू इति। दृंहिताः। शंबरस्य। नव। पुरः। नवतिं। च। श्नथिष्टं। शतं। व

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ र्विनः। सहस्रं। चासाकं। हृथः। अप्रति। असुरस्य। वीरान्। इयं। मनीषा। बृहती। बृहंतं। उरुऽक्रमा। तवसा।
८२ वर्द्धयंती। ररे। वां। स्तोमं। विदथेषु। विष्णो इति। पिन्वतं। इषः। वृजनेषु। इंद्रा। वषट्। वां। विष्णो इति। आ। असः। आ।
82 कृणोमि। तत्। मे। जुषस्व। शिपिऽविष्ट। हव्यं। वर्द्धंतु। त्वा। सुऽस्तुतयः। गिरः। मे। ०।। रथा। नु। मर्तः। दयते। सनि
ष्यन्। यः। विष्णवे। उरुऽगायाय। दाशत्। प्र। यः। सत्राचा। मनसा। यजाते। एतावंतं। नर्यं। आऽविवासात्। त्वं।
विष्णो इति। सुऽमतिं। विश्वऽजन्यां। अप्रऽयुतां। एवऽयावः। मतिं। दाः। पर्चः। यथा। नः। सुवितस्य। भूरेः। अश्व
वतः। पुरुऽचंद्रस्य। रायः। त्रिः। देवः। पृथिवीं। एषः। एतां। वि। चक्रमे। शतऽअर्चसं। महिऽना। प्र। विष्णुः। अस्तु।
तवसः। तवीयान्। त्वेषं। हि। अस्य। स्थविरस्य। नाम। वि। चक्रमे। पृथिवीं। एषः। एतां। क्षेत्राय। विष्णुः। मनु ८२

© Dharmartha Trust J&K. Digitized by eGangotri

षा।दशस्यन्।ध्रुवासः।अस्य।कीरयः।जनासः।उरुःक्षितिं।सुःजनिमा।चकार।प्र।तत्।ते।अद्य।शिपिःवि
ष्ट।नाम।अर्यः।शंसामि।वयुनानि।विद्वान्।तं।त्वा।गृणामि।तवसं।अतव्यान्।क्षयंतं।अस्य।रजसः।प
राके।किं।इत्।ते।विष्णो।इति।परिःचक्ष्यं।भूत्।प्र।यत्।ववक्षे।शिपिःविष्टः।अस्मि।मा।वर्पः।अस्मत्।
अप।गूह।एतत्।यत्।अन्यःरूपः।संःइथे।बभूथ।०॥२५॥इति पंचमाष्टके षष्ठोऽध्यायः॥ ॥ओम्॥
तिस्रः षट् पार्जन्यं तु पर्जन्याय प्र गायत्रं द्वितीया पादनिवृदेने कुमार आग्नेयो परस्य द्वसिष्ठ एव वार्
ष्टिकामः संवत्सरं दश पर्जन्यस्तुतिः संहृष्टान् मंडूकास्तुष्टावाद्यानुष्टुबिंद्रासोमा पंचाधिकैंद्रासो
मं राक्षोघ्नं शापाभिशापप्रायं षट्सप्तम्याद्या जगत्य एकविंशीत्रयोविंश्यौ चाष्टादशी मारुती चेद

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. शामीचतुर्दश्यावाग्नेय्यौ द्व्येकादश्यं स्यानुष्टुप् नवमीद्वादशीत्रयोदशी सौम्यः सप्तदशीगाव्यष्ट
८३ मीषोडश्यौ वैश्वौ प्रवर्त्तयेति च नस्त्रैष्टुंध्नौ मा नो रक्षइत्यषेरात्मन आशी रुत्तरोर्धर्चैः पृथिव्यंतरिक्षं
द्यौरिलिंदैवतः परं गायत्रं प्राग्वत्सप्रैषिश्चानुक्रगोत्रः प्राग्व्रस्याका प्रोष्टमं मंडलं मा चिच्चतुस्त्रिं
दि शन्मेधातिथिमेध्यातिथीऐंद्रं बार्हतं प्रगाथादि द्वित्रिष्टुबंतमाद्येद्वृचं प्रगाथोपश्यत्स घोरःसन्प्रागु
ःकण्वस्य पुत्रतामगात्प्लायोगिश्चासंगोयः स्त्रीभूत्वा पुमानभूत्स मेध्यातिथये दानं दत्वास्तुहि स्तुही
ति चतसृभिरात्मानं तुष्टाव पत्नी चास्यांगिरसी शश्वती पुंस्त्वमुपलभ्यैनं प्रीतांत्यया तुष्टाव इदं व सोहि
चत्वारिंशन्मेधातिथिरांगिरसश्च प्रियमेधः स्वादवो नुष्टुबंत्याभ्यां मेधातिथिर्विभिंदोर्दानं तुष्टावापि ८३

© Dharmartha Trust J&K. Digitized by eGangotri

बद्धलुविंशतिमैध्यालिथिः प्रागाथं वत्तुष्टुप् गायत्र्यौ बृहती चांत्याः कौरयाणस्य पाकस्थाम्नो दानस्तु
तिर्यंदिं इसैकादेवा लिथिस्त्रचौत्यः पुरउष्णिगंतः कुरुं गस्य दानस्तुतिस्तत्सूर्वो ध्वनस्त्रः पोहम्येयावा ॥
ओम् ॥ तिस्रः। वाचः। प्र। वद। ज्योतिःऽअग्राः। याः। एतत्। [illegible] दुह्रे। मधुःदोघं। ऊधः। सः। वत्सं। कृण्वन्।
गर्भं। ओषधीनां। सद्यः। जातः। वृषभः। रोरवीति। यः। वर्द्धनः। ओषधीनां। यः। अपां। यः। विश्वस्य। जगतः।
देवः। ईशे। सः। त्रिऽधातु। शरणं। शर्म। यंसत्। त्रिऽवर्तु। ज्योतिः। सुऽअभिष्टि। अस्मे इति। स्तरीः। ऊं इ
ति। त्वत्। भवति। सूते। ऊं इति। त्वत्। यथाऽवशं। तन्वं। चक्रे। एषः। पितुः। पयः। प्रति। गृभ्णाति। माता।
तेन। पिता। वर्द्धते। तेन। पुत्रः। यस्मिन्। विश्वानि। भुवनानि। तस्थुः। तिस्रः। द्यावः। त्रेधा। सस्रुः। आपः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ त्रयः। कोशासः। उप्ऽसेचनासः। मध्वः। श्चोतंति। अभितः। विऽरप्शं। इंद्राय। चः। पर्जन्याय। स्वऽराजे। हृदः। अ
८४ स्तु। अंतरं। तत्। जुजोषत्। मयःऽभुवः। वृष्टयः। संतु। अस्मे इति। सुऽपिप्पलाः। ओषधीः। देवऽगोपाः। सः।
रेतःऽधाः। वृषभः। शश्वतीनां। तस्मिन्। आत्मा। जगतः। तस्थुषः। च। तत्। मा। ऋतं। पातु। शतऽशारदाय।
या॥३॥ पर्जन्याय। प्र। गायत। दिवः। पुत्राय। मीळ्हुषे। सः। नः। यवसं। इच्छतु। यः। गर्भं। ओषधीनां। गवां।
कृणोति। अर्वतां। पर्जन्यः। पुरुषीणां। तस्मै। इत्। आस्ये। हविः। जुहोत। मधुमत्ऽतमं। इळां। नः। संऽय
तं। करत्॥२॥ संवत्सरं। शशयानाः। ब्राह्मणाः। व्रतऽचारिणः। वाचं। पर्जन्यऽजिन्वितां। प्र। मंडूकाः। अ
वादिषुः। दिव्याः। आपः। अभि। यत्। एनं। आयन्। दृतिं। न। शुष्कं। सरसी इति। शयानं। गवां। अह। न ८४

84

© Dharmartha Trust J&K. Digitized by eGangotri

मायुः। वसिनीनां। मंडूकानां। वग्नुः। अत्र। सं। एति। यत्। ईं। एनान्। उशतः। अभि। अवर्षीत्। तृष्याऽ
वतः। प्रावृषि। आऽगतायां। अख्खलीकृत्या। पितरं। न। पुत्रः। अन्यः। अन्यं। उप। वदंतं। एति। अन्यः।
अन्यं। अनु। गृभ्णाति। एनोः। अपां। प्रऽसर्गे। यत्। अमंदिषातां। मंडूकः। यत्। अभिऽवृष्टः। कनिस्क
न्। पृश्निः। संऽपृंक्ते। हरितेन। वाचं। यत्। एषां। अन्यः। अन्यस्य। वाचं। शाक्तस्यऽइव। वदति। शिक्षमा
णः। सर्वं। तत्। एषां। समृधाऽइव। पर्व। यत्। सुऽवाचः। वदथन। अधि। अप्ऽसु॥ ३॥ गोऽमायुः। ए
कः। अजऽमायुः। एकः। पृश्निः। एकः। हरितः। एकः। एषां। समानं। नाम। बिभ्रतः। विऽरूपाः। पुरुऽ
त्रा। वाचं। पिपिशुः। वदंतः। ब्राह्मणासः। [illegible] अतिऽरात्रे। न। सोमे। सरः। न। पूर्णं। अभितः। वदंतः। सं

© Dharmartha Trust J&K. Digitized by eGangotri

प·पं· वत्सरस्य। अहःऽरिति। तत्। परि। स्थ। यत्। मंडूकाः। प्रावृषीणं। बभूव। ब्राह्मणासः। सोमिनः। वाचं। अक्र
८५ त। ब्रह्म। कृण्वंतः। परिवत्सरीणं। अध्वर्यवः। घर्मिणः। सिस्विदानाः। आविः। भवंति। गुह्याः। न। के। चित्।
देवऽहितिं। जुगुपुः। द्वादशस्य। ऋतुं। नरः। न। प्र। मिनंति। एते। संवत्सरे। प्रावृषि। आऽगतायां। तप्ताः।
घर्माः। अश्नुवते। विऽसर्गं। गोऽमायुः। अदात्। अजऽमायुः। अदात्। पृश्निः। अदात्। हरितः। नः। वसू
नि। गवां। मंडूकाः। ददतः। शतानि। सहस्रऽसावे। प्र। तिरंते। आयुः।।१०।। इंद्रासोमा। तपतं। रक्षः। उब्ज
तं। नि। अर्पयतं। वृषणा। तमःऽवृधः। परा। शृणीतं। अचितः। नि। ओषतं। हतं। नुदेथां। नि। शिशीतं।
अत्रिणः। इंद्रासोमा। सं। अघऽशंसं। अभि। अघं। तपुः। ययस्तु। चरुः। अग्निवान्ऽइव। ब्रह्मऽद्विषे। ८५

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रासोमा।

क्रव्यऽअदे।घोरऽचक्षसे।द्वेषः।धत्तं।अनवायं।किमीदिने।इंद्रासोमा।दुःऽकृतः।वव्रे।अंतः।अनारंभणे।
तमसि।प्र।विध्यतं।यथा।न।अतः।पुनः।एकः।चन।उतऽअयत्।तत्।वां।अस्तु।सहसे।मन्युऽमत्।शवः।
इंद्रासोमा।वर्तयतं।दिवः।वधं।सं।पृथिव्याः।अघऽशंसाय।तर्हणं।उत्।तक्षतं।स्वर्यं।पर्वतेभ्यः।येन।रक्षः।
ववृधानं।निःऽजूर्वथः।४।परि।अग्निऽतप्तेभिः।युवं।अश्महन्मऽभिः।तपुःऽवधेभिः।अजरेभिः।अत्रिणः।
नि।पर्शाने।विध्यतं।यंतु।निःऽस्वरं।५।इंद्रासोमा।परि।वां।भूतु।विश्वतः।इयं।मतिः।कक्ष्या।अश्वाऽ
इव।वाजिना।यां।वां।होत्रां।परिऽहिनोमि।मेधया।इमा।ब्रह्माणि।नृपतीइवेतिनृपतीऽइव।जिन्वतं।
प्रति।स्मरेथां।तुजयत्ऽभिः।एवैः।हतं।द्रुहः।रक्षसः।भंगुरऽवतः।इंद्रासोमा।दुःऽकृते।मा।सुऽगं।भूत्।

© Dharmartha Trust J&K. Digitized by eGangotri

पञ्चं· यः। नः। कदा। चित्। अभिऽदासति। द्रुहा। यः। मा। पाकेन। मनसा। चरन्तं। अभिऽचष्टे। अनृतेभिः। वचःऽ
८६ भिः। आपःऽइव। काशिना। संऽगृभीताः। असन्। अस्तु। असतः। इन्द्र। वक्ता। ये। पाकऽशंसं। विऽहरन्ते। एऽ
वैः। ये। वा। भद्रं। दूषयन्ति। स्वधाभिः। अहये। वा। तान्। प्रऽददातु। सोमः। आ। वा। दधातु। निःऽऋतेः। उपऽ
86 स्थे। यः। नः। रसं। दिप्सति। पित्वः। अग्ने। यः। अश्वानां। यः। गवां। तनूनां। रिपुः। स्तेनः। स्तेयऽकृत्। दभ्रं। यः।
एतु। नि। सः। हीयतां। तन्वा। तना। च। द्द। परः। सः। अस्तु। तन्वा। तना। च। तिस्रः। पृथिवीः। अधः। अस्तु।
विश्वाः। प्रति। शुष्यतु। यशः। अस्य। देवाः। यः। नः। दिवा। दिप्सति। यः। च। नक्तं। सुऽविज्ञानं। चिकितुषे।
जनाय। सत्। च। असत्। च। वचसी इति। पस्पृधाते इति। तयोः। यत्। सत्यं। यतरत्। ऋजीयः। तत्। इत्। ८६

© Dharmartha Trust J&K. Digitized by eGangotri

सोमः।अवति।हंति।असत्।न।वै।ऊं इति।सोमः।वृजिनं।हिनोति।न।क्षत्रियं।मिथुया।धारयंतं।हंति।
रक्षः।हंति।असत्।वदंतं।उभौ।इंद्रस्य।प्रसितौ।शयाते इति।यदि।वा।अहं।अनृतदेवः।आस।मोघं।
वा।देवान्।अपि।ऊहे।अग्ने।किं।अस्मभ्यं।जातवेदः।हृणीषे।द्रोघवाचः।ते।निःऋथं।सचंतां।अद्य।
मुरीय।यदि।यातुधानः।अस्मि।यदि।वा।आयुः।ततप।पुरुषस्य।अध।सः।वीरैः।दशभिः।वि।यूयाः।
यः।मा।मोघं।यातुधान।इति।आह॥७॥यः।मा।अयातुं।यातुधान।इति।आह।यः।वा।रक्षाः।
शुचिः।अस्मि।इति।आह।इंद्रः।तं।हंतु।महता।वधेन।विश्वस्य।जंतोः।अधमः।पदीष्ट।प्र।या।जिगा
ति।खर्गलाऽइव।नक्तं।अप।द्रुहा।तन्वं।गूहमाना।वव्रान्।अनंतान्।अव।सा।पदीष्ट।ग्रावाणः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं० घ्नंतु।रक्षसः।उपब्दैः।वि।तिष्ठध्वं।मरुतः।विक्षु।इच्छत।गृभायत।रक्षसः।सं।पिनष्टन।वयः।ये।भूत्वी।प
८१ तयंति।नक्तऽभिः।ये।वा।रिपः।दधिरे।देवे।अध्वरे।प्र।वर्तय।दिवः।अश्मानं।इंद्र।सोमऽशितं।मघऽवन्।
सं।शिशाधि।प्राक्तात्।अपाक्तात्।अधरात्।उदक्तात्।अभि।जहि।रक्षसः।पर्वतेन।एते।ऊं इति।त्ये।प
87 तयंति।श्वऽयातवः।इंद्रं।दिप्संति।दिप्सवः।अदाभ्यं।शिशीते।शक्रः।पिशुनेभ्यः।वधं।नूनं।सृजत्।अश
निं।यातुमत्ऽभ्यः॥८॥ इंद्रः।यातूनां।अभवत्।पराऽशरः।हविःऽमथीनां।अभि।आऽविवासतां।अभि।
इत्।ऊं इति।शक्रः।परशुः।यथा।वनं।पात्राऽइव।भिंदन्।सतः।एति।रक्षसः।उलूकऽयातुं।शुशुलूकऽयां
तुं।जहि।श्वऽयातुं।उत।कोकऽयातुं।सुपर्णऽयातुं।उत।गृध्रऽयातुं।दृषदाऽइव।प्र।मृण।रक्षः।इंद्र।मा।नः। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

रक्षः।अभि।नट्।यातुऽमावतां।अप।उच्छतु।मिथुना।या।किमीदिना।पृथिवी।नः।पार्थिवात्।पातु।अंहसः।
।अंतरिक्षं।दिव्यात्।पातु।अस्मान्।इंद्र।जहि।पुमांसं।यातुऽधानं।उत।स्त्रियं।मायया।शाशदानां।वि
ऽग्रीवासः।मूरऽदेवाः।ऋदंतु।मा।ते।दृशन्।सूर्यं।उत्ऽचरंतं।प्रति।चक्ष्व।वि।चक्ष्व।इंद्रः।च।सोम।जागृतं।
रक्षःऽभ्यः।वधं।अस्यतं।अशनिं।यातुमत्ऽभ्यः।।१।।इति सप्तमं मंडलं।। अनुवाकः।।मा।चित्।अन्यत्।वि
।शंसत।सखायः।मा।रिषण्यत।इंद्रं।इत्।स्तोत।वृषणं।सचा।सुते।मुहुः।उक्था।च।शंसत।अवऽक्रक्षि
णं।वृषभं।यथा।अजुरं।गां।न।चर्षणिऽसहं।विऽद्वेषणं।संऽवननं।उभयंऽकरं।मंहिष्ठं।उभयाविनं।
यत्।चित्।हि।त्वा।जनाः।इमे।नाना।हवंते।ऊतये।अस्माकं।ब्रह्म।इदं।इंद्र।भूतु।ते।अहा।विश्वा।च।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. वहिनं । वि । तर्तूर्यन्ते । मघ॰वन् । विपः॰चितः । अर्यः । विपः । जनानां । उप । क्रमस्व । पुरु॰रूपं । आ । भर । वाजं । नेदि
९८ ष्ठं । ऊतये । महे । चन । त्वां । अद्रि॰वः । परा । शुल्काय । देयां । न । सहस्राय । न । अयुताय । वज्रि॰वः । न । शताय । शत॰मघ ॥ ३ ॥ वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुं॰जतः । माता । च । मे । छदयथः । समा । वसो
इति । वसु॰त्वनाय । राधसे । क्व । इयथ । क्व । इत् । असि । पुरु॰त्रा । चित् । हि । ते । मनः । अलर्षि । युध्म । खज॰कृत् । पुरं॰दर । प्र । गायत्राः । अगासिषुः । प्र । अस्मै । गायत्रं । अर्चत । वावातुः । यः । पुरं॰दरः । याभिः । काण्वस्य । उप । बर्हिः । आ॰सदं । यासत् । वज्री । भिनत् । पुरः । ये । ते । सन्ति । दश॰ग्विनः । शतिनः । ये । सहस्रिणः ।
अश्वासः । ये । ते । वृषणः । रघु॰द्रुवः । तेभिः । नः । तूयं । आ । गहि । आ । तु । अद्य । सबः॰दुघां । हुवे । गायत्र॰ ९८

© Dharmartha Trust J&K. Digitized by eGangotri

वेपसं। इंद्र। धेनुं। सुऽदुघां। अन्यां। इषं। उरुऽधारां। अरंऽकृतं॥ ३१॥ यत्। तुदत्। सूरः। एतशं। वंकू इति।
वातस्य। पर्णिना। वहत्। कुत्सं। आर्जुनेयं। शतऽक्रतुः। त्सरत्। गंधर्वं। अस्तृतं। यः। ऋते। चित्। अभिऽ
श्रिषः। पुरा। जत्रुऽभ्यः। आऽतृदः। संऽधाता। संऽधिं। मघऽवा। पुरुऽवसुः। इष्कर्ता। विऽह्रुतं। पुनरिति। मा।
भूम। निष्ट्याःऽइव। इंद्र। त्वत्। अरणाःऽइव। वनानि। न। प्रऽजहितानि। अद्रिऽवः। दुरोषासः। अमन्महि। अ
मन्महि। इत्। अनाशवः। अनुग्रासः। च। वृत्रऽहन्। सकृत्। सु। ते। महता। शूर। राधसा। अनु। स्तोमं। मु
दीमहि। यदि। स्तोमं। मम। श्रवत्। अस्माकं। इंद्रं। इंदवः। तिरः। पवित्रं। ससृऽवांसः। आशवः। मंदंतु। तु
आ त्वद्य ग्र्यऽवृधः॥ १२॥ ७॥ सधऽस्तुतिं। ववातुः। सख्युः। आ। गहि। उपऽस्तुतिः। मघोनां। प्र। त्वा। अवतु। अध।

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. ते। वृषिभिः। सुऽस्तुतिं। सोता। हि। सोमं। अद्रिऽभिः। आ। ईं। एनं। अपः। सुऽधावत। गव्या। वस्त्राऽइव। वास
८० यंतः। इत्। नरः। निः। धुक्षन्। वक्षणाभ्यः। अध। ज्मः। अध। वा। दिवः। बृहतः। रोचनात्। अधि। अया। वृ
हुस्व। तन्वा। गिरा। मम। आऽजाता। सुऽक्रतो इति सुऽक्रतो। पृण। इंद्राय। सु। मदिन्ऽतमं। सोमं। सोत। नु।
वरेण्यं। शक्रः। एनं। पीपयत्। विश्वया। धिया। हिन्वानं। न। वाजऽयुं। मा। त्वा। सोमस्य। गल्दया। स
दा। याचन्। अहं। गिरा। भूर्णिं। मृगं। न। सवनेषु। चुक्रुधं। कः। ईशानं। न। याचिषत्॥ २३॥ मदेन। इ
षितं। मदं। उग्रं। उग्रेण। शवसा। विश्वेषां। तरुतारं। मदऽच्युतं। मदे। हि। स्म। ददाति। नः। शेवारे। वा
र्या। पुरु। देवः। मर्ताय। दाशुषे। सः। सुन्वते। च। स्तुवते। च। रासते। विश्वऽगूर्तः। अरिऽस्तुतः। आ। इं ८०

द्र।याहि।मत्स्व।चित्रेण।देव।राधसा।सरः।न।प्रासि।उदरं।सपीतिऽभिः।आ।सोमेभिः।उरु।स्फिरं।
आ।त्वा।सहस्रं।आ।शतं।युक्ताः।रथे।हिरण्यये।ब्रह्मऽयुजः।हरयः।इंद्र।केशिनः।वहंतु।सोमऽपीतये।
आ।त्वा।रथे।हिरण्यये।हरी इति।मयूरऽशेप्या।शितिऽपृष्ठा।वहतां।मध्वः।अंधसः।विवक्षणस्य।पी
तये।३४।पिब।तु।अस्य।गिर्वणः।सुतस्य।पूर्वपाःऽइव।परिऽकृतस्य।रसिनः।इयं।आऽसुतिः।चारुः।
मदाय।पत्यते।यः।एकः।अस्ति।दंसना।महान्।उग्रः।अभि।व्रतैः।गमत्।सः।शिप्री।न।सः।योषत्।
आ।गमत्।हवं।न।परि।वर्जति।त्वं।पुरं।चरिष्णवं।वधैः।शुष्णस्य।सं।पिणक्।त्वं।भाः।अनु।चरः।अध।
द्विता।यत्।इंद्र।हव्यः।भुवः।मम।त्वा।सूरे।उत्ऽइते।मम।मध्यंदिने।दिवः।मम।प्रऽपित्वे।अपिऽशर्वरे।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. वसो इति। आ। स्तोमासः। अवृत्सत। स्तुहि। स्तुहि। इत्। एते। घ। ते। मंहिष्ठासः। मघोनां। निंदितऽअश्वः।
९० प्रऽपथी। परमऽज्याः। मघस्य। मेध्यऽअतिथे॥ १५॥ आ। यत्। अश्वान्। वनन्ऽवतः। श्रद्धया। अहं। रथे।
रुहं। उत। वामस्य। वसुनः। चिकेतति। यः। अस्ति। याद्वः। पशुः। यः। ऋज्रा। मह्यं। मंहते। सह। त्वचा। हि
९० रण्यया। एषः। विश्वानि। अभि। अस्तु। सौभगा। आऽसंगस्य। स्वनत्ऽरथः। अध। प्लायोगिः। अति। दा
सत्। अन्यान्। आऽसंगः। अग्ने। दशऽभिः। सहस्रैः। अध। उक्षणः। दश। मह्यं। रुशंतः। नळाः। इव। सरः
सः। निः। अतिष्ठन्। अनु। अस्य। स्थूरं। ददृशे। पुरस्तात्। अनस्थः। ऊरुः। अवऽरंबमाणः। शश्वती।
नारी। अभिऽचक्ष्य। आह। सुऽभद्रं। अर्य। भोजनं। बिभर्षि॥ १६॥ इदं। वसो इति। सुतं। अंधः। पिब। सुऽ ९०

© Dharmartha Trust J&K. Digitized by eGangotri

पूर्णं। उदरं। अनाभयिन्। ररिम। ते॥ नृऽभिः। धूतः। सुतः। अश्नैः। अव्यः। वारैः। परिऽपूतः। अश्वः। न। निक्तः।
नदीषु॥ तं। ते। यवं। यथा। गोभिः। स्वादुं। अकर्म। श्रीणंतः। इंद्र। त्वा। अस्मिन्। सधऽमादे॥ इंद्रः। इत्। सो
मऽपाः। एकः। इंद्रः। सुतऽपाः। विश्वऽआयुः। अंतः। देवान्। मर्त्यान्। च॥ न। यं। शुक्रः। न। दुःऽआशीः। न। तृप्राः। वे २
उरुऽव्यचसं। अपऽस्पृण्वते। सुऽहार्दं॥ ४॥ गोभिः। यत्। ईं। अन्ये। अस्मत्। मृगं। न। व्राः। मृगयंते। अ
भिऽसरंति। धेनुऽभिः॥ त्रयः। इंद्रस्य। सोमाः। सुतासः। संतु। देवस्य। स्वे। क्षये। सुतऽपाव्नः॥ त्रयः। को
शासः। श्चोतंति। तिस्रः। चम्वः। सुऽपूर्णाः। समाने। अधि। भार्मन्॥ शुचिः। असि। पुरुनिःऽस्थाः। क्षी
रैः। मध्यतः। आऽशीर्तः। दध्ना। मंदिष्ठः। शूरस्य॥ इमे। ते। इंद्र। सोमाः। तीव्राः। अस्मे इति। सुतासः। शु

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. क्रः। आऽशिरं। या। चेतं॥ ३०॥ तां। तां। आऽशिरं। पुरोळाशं। इंद्र। इमं। सोमं। श्रीणीहि। रेवंतं। हि। त्वा। श्टणो
९३ मि। हृत्ऽसु। पीतासः। युध्यंते। दुःऽमदासः। न। सुरायां। ऊधः। न। नग्नाः। जरंते। रेवान्। इत्। रेवतः। स्तो
91 ता। स्यात्। त्वाऽवतः। मघोनः। प्र। इत्। ऊं इति। हरिऽवः। श्रुतस्य। उक्थं। चन। शस्यमानं। अगोः। अरिः
। आ। चिकेत। न। गायत्रं। गीयमानं। मा। नः। इंद्र। पीयत्नवे। मा। शर्द्धते। परा। दाः। शिक्ष। शचीऽवः
वयमुत्वा शचीभिः॥ १०॥ १॥ तदित्ऽअर्थाः। इंद्र। त्वाऽयंतः। सखायः। कण्वाः। उक्थेभिः। जरंते। न। घ। ईं। अन्य
इन्द्र। त्। आ। पपन। वज्रिन्। अपसः। नविष्टौ। तव। ऊं इति। स्तोमं। चिकेत। इच्छंति। देवाः। सुन्वंतं। न। स्वप्ना
य। स्पृहयंति। यंति। प्रऽमादं। अतंद्राः। ओ इति। सु। प्र। याहि। वाजेभिः। मा। हृणीथाः। अभि। अस्मा ९३

© Dharmartha Trust J&K. Digitized by eGangotri

न्ना। महान्नऽइव। युवऽजानिः। मो इति। सु। अया। दुःऽहनौ। यान्ना। सायं। करत्। आरे। अस्मत्। अभीरःऽइव।
आमाता॥२॥१॥ वि। स्मा। हि। अस्य। वीरस्य। भूरिऽदावरीं। सुऽमतिं। त्रिषु। जातस्य। मनांसि। आ। तु। सिं
चा। कृण्वऽ। मंतं। ना। घा। वि। स्मा। रा। वसा। ना। तना। युशः। ऽलं। रां। शलेऽ ऊतेः। ज्येष्ठेना। सोतः। इंद्राय। सोमं। वीराय।
शक्राय। भर। पिबत्ना। नर्यो। या। यः। वेदिषः। अभ्यथिष्ठा। अभ्यवं। तं। जरितःऽस्ध्यः। वाजं। स्तोतरऽस्ध्यः। गोऽमं
तं। पन्यंऽपन्यं। इत्। सोतारः। आ। धावत। मद्याय। सोमं। वीराय। शूराय॥२॥ पात। वृत्रऽहा। सुतं। आ।
घा। गमत्। न। आरे। अस्मत्। नि। यमत्। शतऽऊतिः। आ। इह। हरी इति। ब्रह्मऽयुजा। शग्मा। वक्षतः। स
खायं। गीःऽभिः। श्रुतं। गिर्वणसं॥ स्वादवः। सोमाः। आ। याहि। श्रीताः। सोमाः। आ। याहि। शिप्रिन्॥ ३

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ षिऽवः। शचीऽवः। न। अर्यः। अछ। सधऽमादे। स्तुतः। च। याः। त्वा। वर्द्धंति। महे। राधसे। नृम्णाय। इंद्र। कारि
१२ णं। वृधंतः। गिरः। च। याः। ते। गिर्वाहः। उक्था। च। तुभ्यं। तानि। सत्रा। दधिरे। शवांसि॥ २२॥ एव। इत्। ए
षः। तुविऽकूर्मिः। वाजान्। एकः। वज्रऽहस्तः। सनात्। अमृक्तः। दयते। हंता। वृत्रं। दक्षिणेन। इंद्रः। पुरु।
९२ पुरुऽहूतः। महान्। महीभिः। शचीभिः। यस्मिन्। विश्वाः। चर्षणयः। उत। च्यौत्ना। ज्रयांसि। च। अनु।
घ। इत्था। मंदी। मघोनः। एषः। एतानि। चकार। इंद्रः। विश्वा। यः। अति। शृण्वे। वाजऽदावा। मघोनां। प्रऽ
भर्ता। रथं। गव्यंतं। अपाकात्। चित्। यः। अवति। इनः। वसु। सः। हि। वोळ्हा॥ २३॥ सनिता। विप्रः। अर्व
त्ऽभिः। हंता। वृत्रं। नृऽभिः। शूरः। सत्यः। अविता। विधंतः। यजध्व। एनं। प्रियऽमेधाः। इंद्रं। सत्राचा। मनं १२

© Dharmartha Trust J&K. Digitized by eGangotri

सायः। भूत्। सोमैः। सुऽसः। मह्नां। गाथऽश्रवसः। सत्ऽपतिं। श्रवःऽकामं। पुरुऽत्मानं। कण्वासः। गात। वाजिनं।
यः। ऋते। चित्। [illegible] गाः। पदेभ्यः। दात्। सखा। नृऽभ्यः। शचीऽवान्। यः। अस्मिन्। कामं। अश्रियन्। इत्था। धीऽवं
तं। अद्रिऽवः। काण्वं। मेध्यऽअतिथिं। मेषः। भूतः। अभि। यन्। अयः। शिक्ष। विभिंदो इति विऽभिंदो। अस्मै। च
त्वारि। अयुता। ददत्। अष्ट। परः। सहस्रा। उत। सु। त्ये इति। पयःऽवृधा। माकी इति। रणस्य। नप्त्या। जनिऽत्वना
याम। महे। २४। आ। पिब। सुतस्य। रसिनः। मत्स्व। नः। इंद्र। गोऽमतः। आपिः। नः। बोधि। सधऽमाद्यः। वृधे। अस्मा
न्। अवंतु। ते। धियः। भूयाम। ते। सुऽमतौ। वाजिनः। वयं। मा। नः। स्तः। अभिऽमातये। अस्मान्। चित्राभिः।
अवतात्। अभिष्टिऽभिः। आ। नः। सुम्नेषु। यमय। इमाः। ऊं इति। त्वा। पुरुवसो इति पुरुऽवसो। गिरः। वर्द्धंतु।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. याः । मम । पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि । स्तोमैः । अनूषत । अयं । सहस्रं । ऋषिऽभिः । सहःऽ
९३ कृतः । समुद्रःऽइव । पप्रथे । सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रऽराज्ये । इंद्रं । इत् । देवऽतातये ।
इंद्रं । प्रऽयति । अध्वरे । इंद्रं । संऽईके । वनिनः । हवामहे । इंद्रं । धनस्य । सातये ॥ २५ ॥ इंद्रः । मह्ना । रोदसी इति ।
पप्रथत् । शवः । इंद्रः । सूर्यं । अरोचयत् । इंद्रे । ह । विश्वा । भुवनानि । येमिरे । इंद्रे । सुवानासः । इंदवः ॥ ० ॥ इंद्रं । स्तो अभि त्वा पूर्वपी तये
मेभिः । आयवः । संऽईचीनाः । अस्वरन् । रुद्राः । गृणंत । पूर्व्यं । अस्य । इत् । इंद्रः । ववृधे । वृष्ण्यं । शवः । मदे ।
सुतस्य । विष्णवि । अद्य । तं । अस्य । महिमानं । आयवः । अनु । स्तुवंति । पूर्वऽथा । तत् । त्वा । यामि । सुऽ
वीर्यं । तत् । ब्रह्म । पूर्वऽचित्तये । येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वं । आविथ । येन । समुद्रं ९३

ऋ.भवे.।सं।३

© Dharmartha Trust J&K. Digitized by eGangotri

असृजः।महीः।अपः।तत्।इंद्र।दृहिता।शवः।सघः।सः।अस्य।महिमा।न।संऽनशे।यं।क्षोणीः।अनु
ऽचक्रदे।रद्धा।शग्धि।नः।इंद्र।यत्।त्वा।रयिं।यामि।सुऽवीर्यं।शग्धि।वाजाय।प्रथमं।सिसासते।शग्धि।
स्तोमाय।पूर्व्य।शग्धि।नः।अस्य।यत्।ह।पौरं।आविथ।धियः।इंद्र।सिसासतः।शग्धि।यथा।रुशमं।
श्यावकं।कृपं।इंद्र।प्र।आवः।स्वःऽनरं।कत्।नव्यः।अतसीनां।तुरः।गृणीत।मर्त्यः।नहि।नु।अस्य।महिमा
नं।इंद्रियं।स्वः।गृणंतः।आनशुः।कत्।ऊं।इति।स्तुवंतः।ऋतऽयंत।देवता।ऋषिः।कः।विप्रः।ओहते।कदा।ह
वं।मघऽवन्।इंद्र।सुन्वतः।कत्।ऊं।इति।स्तुवतः।आ।गमः।उत्।ऊं।इति।स्ये।मधुमत्ऽतमाः।गिरः।स्तोमासः।
ईरते।सत्राऽजितः।धनऽसाः।अक्षितऽऊतयः।वाजऽयंतः।रथाःऽइव।२७।कण्वाःऽइव।भृगवः।सूर्याःऽ

© Dharmartha Trust J&K. Digitized by eGangotri

११. इवा।विश्वं।इत्।धीतं।आनशुः।इंद्रं।स्तोमेभिः।महयंतः।आयवः।प्रियऽमेधासः।अस्वरन्।युक्ष्व।हि।वृत्र
९४ हन्ऽतम।हरीइति।इंद्र।पराऽवतः।अर्वाचीनः।मघऽवन्।सोमऽपीतये।उग्रः।ऋष्वेभिः।आ।गहि।इमे।हि।ते
94 कारवः।वावशुः।धिया।विप्रासः।मेधऽसातये।सः।त्वं।नः।मघऽवन्।इंद्र।गिर्वणः।वेनः।न।शृणुधि।ह
वं।निः।इंद्र।बृहतीभ्यः।वृत्रं।धनुऽभ्यः।अस्फुरः।निः।अर्बुदस्य।मृगयस्य।मायिनः।निः।पर्वतस्य।गाः।
आजः।निः।अग्नयः।रुरुचुः।निः।ऊंइति।सूर्यः।निः।सोमः।इंद्रियः।रसः।निः।अंतरिक्षात्।अधमः।म
हां।अहिं।कृषे।तत्।इंद्र।पौंस्यं।यं।मे।दुः।इंद्रः।मरुतः।पाकऽस्थामा।कौरयाणः।विश्वेषां।त्मना।शो
भिष्ठं।उपऽइव।दिवि।धावमानं।रोहितं।मे।पाकऽस्थामा।सुऽधुरं।कक्ष्यऽप्रां।अदात्।रायः।विऽबोधनं। ९४

© Dharmartha Trust J&K. Digitized by eGangotri

यस्मै। अन्ये। दश। प्रति। धुरं। वहंति। वह्नयः। अस्तं। वयः। न। तुग्र्यं। आत्मा। पितुः। तनूः। वासः। ओजः ऽदाः। अ
भिऽअंजनं। तुरीयं। इत्। रोहितस्य। पाकऽस्थामानं। भोजं। दातारं। अब्रवं॥ २॥ यत्। इंद्र। प्राक्। अपाक्।
उदक्। न्यक्। वा। हूयसे। नृऽभिः। सिम। पुरु। नृऽसूतः। असि। आनवे। असि। प्रऽशर्द्ध। तुर्वशे। यत्। वा। रुमे। रु
शमे। श्यावके। कृपे। इंद्र। मादयसे। सचा। कण्वासः। त्वा। ब्रह्मऽभिः। स्तोमऽवाहसः। इंद्र। आ। यच्छंति। आ। गहि।
यथा। गौरः। अपा। कृतं। तृष्यन्। एति। अव। इरिणं। आऽपित्वे। नः। प्रऽपित्वे। तूयं। आ। गहि। कण्वेषु। सु। स
चा। पिब। मंदंतु। त्वा। मघऽवन्। इंद्र। इंदवः। राधःऽदेयाय। सुन्वते। आऽमुष्य। सोमं। अपिबः। चमू इति। सुतं।
सहः। ज्येष्ठं। तत्। दधिषे। सहः। प्र। चक्रे। सहसा। सहः। बभंज। मन्युं। ओजसा। विश्वे। ते। इंद्र। पृतनाऽयवः। यहो इति।

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. नि । रक्षाःऽइव । यमिरे ॥ २० ॥ सहस्रेणऽइव । सचते । यविऽयुधा । यः । ते । आनट् । उपऽस्तुतिं । पुत्रं । प्रावर्गं । कृणुते ।
९५ सुऽवीर्यं । दाश्नोति । नमउक्तिऽभिः । मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव । महत् । ते । वृष्णः । अभिऽचक्ष्यं ।
कृतं । पश्येम । तुर्वशं । यदुं । सव्यां । अनु । स्फिग्यं । वावसे । वृषा । न । दानः । अस्य । रोषति । मध्वा । संऽपृक्ताः । सा
रघेण । धेनवः । तूयं । आ । इहि । द्रव । पिब । अश्वी । रथी । सुऽरूपः । इत् । गोऽमान् । इत् । इंद्र । ते । सखा । श्वात्रऽ
भाजा । वयसा । सचते । सदा । चंद्रः । याति । सभां । उप । ऋश्यः । न । तृष्यन् । अवऽपानं । आ । गहि । पिब । सोमं ।
वशान् । अनु । निऽमेघमानः । मघऽवन् । दिवेऽदिवे । ओजिष्ठं । दधिषे । सहः ॥ २१ ॥ अध्वर्यो इति । द्रवय । त्वं ।
सोमं । इंद्रः । पिपासति । उप । नूनं । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्रऽहा । स्वयं । चित् । सः । मन्यु ९५

95

© Dharmartha Trust J&K. Digitized by eGangotri

स्तस्थोध्वरभियोयहंनुसवनेदुप। ३

तोदा। भुरिः। जनः। यत्र। सोमस्य। तृपसि। इदं। ते। अन्नं। युज्यं। संऽउक्षितं। तस्य। आ। इहि। प्र। द्रव। पिब। रथेः
स्थाय। अध्वर्यवः। सोमं। इंद्राय। सोतन। अधि। ब्रध्नस्य। अद्रयः। वि। चक्षत। सुऽवं। नः। दाभुः। अध्वरं। उप। ब्र
ध्नं। नुनाता। रथेष्णा। हरी इति। इंद्रो। अपः। स्तुं। वृक्षतः। अर्वांचं। त्वा। अग्ने। प्र। पूषणं। वृणीमहे। युज्याय। पुरुऽवसुं।
सः। शक्र। शिक्ष। पुरुऽहूत। नः। धिया। तुजे। राये। विऽमोचन। उग्रा। सं। नः। शिशीहि। भुरिजोःऽइव। क्षुरं। रा
स्व। रायः। विऽमोचन। त्वे इति। तत्। नः। सुऽवेदं। उस्रियं। वसु। यं। त्वं। हिनोषि। मर्त्यं। वेमि। त्वा। पूषन्। ऋंजसे।
वेमि। स्तोतवे। आघृणे। न। तस्य। वेमि। अरणं। हि। तत्। वसो इति। स्तुषे। पज्राय। साम्ने। परा। गावः। यवसं। क
त्। चित्। आघृणे। नित्याः। रेक्णः। अमर्त्या। अस्माकं। पूषन्। अविता। शिवः। भव। मंहिष्ठः। वाजऽसातये।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. स्थूरं।राधः।शतः अश्वं।कुरुंगस्य।दिविष्टिषु।राज्ञः।त्वेषस्य।सुभगस्य।रातिषु।तुर्वशेषु।अमन्मुहि।धी
१६ भिः।सातानि।काण्वस्य।वाजिनः।प्रियमेधैः।अभिद्युभिः।षष्टिं।सहस्रा।अनु।निःमजां।अजे।निः
यूथानि।गवां।ऋषिः।दृक्षाः।चित्रा।मे।अभिःपित्वे।अररणुः।गां।भजंत।मेहना।अश्वं।भजंत।मेहना।३३॥
96 इति पंचमाष्टके सप्तमोध्यायः॥ ॥ॐम्॥ ॥दूरादेकान्नचत्वारिंशद्वृत्तानि तिथिराश्विनं द्वि बृहत्यनु
ष्टुबंते मंत्यासः पंचाद्यर्चांश्च्चेयकशोर्दनस्तुतिः प्रेयद्वःषत्रिंशात्पुनर्वत्सो मारुतं मानस्यधिकास्वध्वं
स आश्विनं त्यानुष्टुभं त्वान्नूनं सैका शशकर्णोंस्येगायत्र्याउपाद्येचा धाचनुर्थीषड्जी चतुर्दश्यापंचवृह
त्यः पंचमी ककुबद्दशम्याघो[illegible]स्त्रिष्टुप्पविराजगत्सौ यत्स्थःषट्प्रगाथो पश्यद्वृहती मेध्ये ज्योतिर १६
द्दम हांइंद्रो ष्टा चत्वारिंशद्वृक्तस्तत चोंसत्यदिदिरस्यपार्शव्य
ग नस्ततिः
© Dharmartha Trust J&K. Digitized by eGangotri

नुष्टुब्वास्तारपंक्तिः प्रगाथः स्त्वमग्ने दशावस्त आग्नेयं गायत्रं त्र्यादेवीत्रिष्टुब्वा यावतिष्ठो पाद्या वर्द्धमानाः
ओम्॥ दूरात्। इहऽइव। यत्। सती। अरुणऽप्सुः। अशिश्वितत्। वि। भानुं। विश्वधा। अतनत्। नृऽवत्। दस्रा।
मनःऽयुजा। रथेन। पृथुऽपाजसा। सचेथे इति। अश्विना। उषसं। युवाभ्यां। वाजिनीवसू इति वाजिनीऽव
सू। प्रति। स्तोमाः। अदृक्षत। वाचं। दूतः। यथा। ओहिषे। पुरुऽप्रिया। नः। ऊतये। पुरुऽमन्द्रा। पुरुवसू इति पुरुऽ
वसू। स्तुषे। कण्वासः। अश्विना। मंहिष्ठा। वाजऽसातमा। इषयन्ता। शुभः। पती इति। गन्तारा। दाशुषः। गृ
हं॥ ३॥ ता। सुऽदेवाय। दाशुषे। सुऽमेधां। अविऽतारिणीं। घृतैः। गव्यूतिं। उक्षतं। आ। नः। स्तोमं। उप। द्रव
त्। तूयं। श्येनेभिः। आशुऽभिः। यातं। अश्वेभिः। अश्विना। येभिः। तिस्रः। पराऽवतः। दिवः। विश्वानि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ रोचना । त्रीन् । अक्तून् । परिऽदीयथः । उत । नः । गोऽमतीः । इषः । उत । सातीः । अहःऽविदा । वि । पथः । सातये । सितं ।
१० आ । नः । गोऽमन्तं । अश्विना । सुऽवीरं । सुऽरथं । रयिं । वोळ्हं । अश्वऽवतीः । इषः । वीरऽधाना । शुभः । पती इति । दस्रा ।
97 हिरण्यवर्तनी इति हिरण्यऽवर्तनी । पिबतं । सोम्यं । मधु । अस्मभ्यं । वाजिनीवसू इति वाजिनीऽवसू । मघव
त्ऽभ्यः । च । सऽप्रथः । छर्दिः । यन्तं । अदाभ्यं । नि । सु । ब्रह्म । जनानां । या । अविष्टं । तूयं । आ । गतं । मो इति । सु । अ
न्यान् । उप । अरतं । अस्य । पिबतं । अश्विना । युवं । मदस्य । चारुणः । मध्वः । रातस्य । धिष्ण्या । अस्मे इति । आ ।
वहतं । रयिं । शतऽवन्तं । सहस्रिणं । पुरुऽक्षुं । विश्वऽधायसं । पुरु । त्रा । चित् । हि । वां । नरा । विऽह्वयन्ते । मनी
षिणः । वाघत्ऽभिः । अश्विना । आ । गतं । जनासः । वृक्तऽबर्हिषः । हविष्मन्तः । अरंऽकृतः । युवां । हवन्ते । अश्वि १८

© Dharmartha Trust J&K. Digitized by eGangotri

यद्वारध्योविभि

ना। अस्माकं। अद्य। वां। अयं। स्तोमः। वाहिष्ठः। अंतमः। युवाभ्यां। भूतु। अश्विना। यः। ह। वां। मधुनः। दृतिः। आऽ
हितः। रथे। चऽर्षणे। ततः। पिबतं। अश्विना। तेन। नः। वाजिनीवसू इति वाजिनीऽवसू। पश्वे। तोकाय। शं। गवे। व
हतं। पीवरीः। इषः। ।८। उत। नः। दिव्याः। इषः। उत। सिंधून्। अहः॑ऽविदा। अप। द्वाराऽइव। वर्षथः। कदा। वां। तौग्र्यः
विधत्। समुद्रे। जहितः। नरा। युवं। कण्वाय। नासत्या। अपिऽरिप्ताय। हर्म्ये। शश्वत्। ऊतीः। दशस्यथः। ताभिः
।आ। यातं। ऊतिऽभिः। नव्यसीभिः। सुशस्तिऽभिः। यत्। वां। वृषण्वसू इति वृषण्ऽवसू। हुवे। यथा। चित्। क
ण्वं। आवतं। प्रियऽमेधं। उपऽस्तुतं। अत्रिं। शिंजारं। अश्विना। ।५। यथा। उत। कृत्व्ये। धने। अंशुं। गोषु। अग
स्त्यं। यथा। वाजेषु। सोभरिं। एतावत्। वां। वृषण्वसू इति वृषण्ऽवसू। अतः। वा। भूयः। अश्विना। गृणंतः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. सुम्नं। ईमहे। रथं। हिरण्यऽवंधुरं। हिरण्यऽअभीशुं। अश्विना। आ। हि। स्थाथः। दिविऽस्पृशं। हिरण्ययी। वां। र
१८ भिः। ईषा। अक्षः। हिरण्ययः। उभा। चक्रा। हिरण्यया। तेन। पराऽवतः। चित्। आ। गतं। उप। इमां। सुऽस्तुतिं। मम।। नेनेनोक जिनीवसु
धा। आ। नहेथे इति। पराकात्। पूर्वीः। अश्नंतौ। अश्विना। इषः। दासीः। अमर्त्या। आ। नः। द्युम्नैः। आ। श्रवःऽ
98 भिः। आ। राया। यातं। अश्विना। पुरुऽचंद्रा। नासत्या। आ। इह। वां। प्रुषितऽप्सवः। वयः। वहंतु। पर्णिनः। अ
च्छ। सुऽअध्वरं। जनं। रथं। वां। अनुऽगायसं। यः। इषा। वर्तते। सह। न। चक्रं। अभि। बाधते। हिरण्ययेन। रथे
न। द्रुवत्पाणिऽभिः। अश्वैः। धीऽजवना। नासत्या।। ७।। युवं। मृगं। जागृऽवांसं। स्वदथः। वा। वृषण्वसू इ
ति वृषणऽवसू। ता। नः। पृंक्तं। इषा। रयिं। ता। मे। अश्विना। सनीनां। विद्यातं। नवानां। यथा। चित्। चैद्यः। १८

© Dharmartha Trust J&K. Digitized by eGangotri

कशुः । शतं । उष्ट्रानां । ददत् । सहस्रा । दश । गोनां । यः । मे । हिरण्यऽसंदृशः । दश । राज्ञः । अमंहत । अधःऽपदाः ।
इत् । चैद्यस्य । कृष्टयः । चर्मऽम्नाः । अभितः । जनाः । माकिः । एना । पथा । गात् । येन । इमे । यंति । चेदयः । अन्यः ।
न । इत् । सूरिः । ओहते । भूरिदावत्ऽतरः । जनः ॥ ८ ॥ अनुवाकः । महान् । इंद्रः । यः । ओजसा । पर्जन्यः । वृष्टि
मान्ऽइव । स्तोमैः । वत्सस्य । ववृधे । प्रऽजां । ऋतस्य । पिप्रतः । प्र । यत् । भरंत । वन्हयः । विप्राः । ऋतस्य । वाह
सा । कण्वाः । इंद्रं । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनं । जामि । ब्रुवत । आयुधं । सं । अस्य । मन्यवे । वि
शः । विश्वाः । नमंत । कृष्टयः । समुद्रायऽइव । सिंधवः । ओजः । तत् । अस्य । तित्विषे । उभे इति । यत् । संऽअ
वर्त्तयत् । इंद्रः । चर्मऽइव । रोदसी इति ॥ ९ ॥ वि । चित् । वृत्रस्य । दोधतः । वज्रेण । शतऽपर्वणा । शिरः । बिभेद ।

© Dharmartha Trust J&K. Digitized by eGangotri

११. वह्निना। इमाः। अभि। प्र। नोनुमः। विपां। अग्रेषु। धीतयः। अग्नेः। शोचिः। न। दिद्युतः। गुहा। सतीः। उप। त्म
११ ना। प्र। यत्। शोचंत। धीतयः। कण्वाः। ऋतस्य। धारया। प्र। तं। इंद्र। नशीमहि। रयिं। गोऽमंतं। अश्विनं। प्र। ब्र
11 ह्म। पूर्वऽचित्तये। अहं। इत्। हि। पितुः। परि। मेधां। ऋतस्य। जग्रभ। अहं। सूर्यःऽइव। अजनि॥१०॥ अहं। प्र
त्नेन। मन्मना। गिरः। शुंभामि। कण्वऽवत्। येन। इंद्रः। शुष्मं। इत्। दधे। ये। त्वां। इंद्र। न। तुष्टुवुः। ऋषयः। ये।
च। तुष्टुवुः। मम। इत्। वर्धस्व। सुऽस्तुतः। यत्। अस्य। मन्युः। अध्वनीत्। वि। वृत्रं। पर्वऽशः। रुजन्। अपः।
समुद्रं। ऐरयत्। नि। शुष्णे। इंद्र। धर्णसिं। वज्रं। जघंथ। दस्यवि। वृषा। हि। उग्र। शृण्विषे। न। द्यावः। इंद्रं। ओ
जसा। न। अंतरिक्षाणि। वज्रिणं। न। विव्यचंत। भूमयः॥११॥ यः। ते। इंद्र। महीः। अपः। स्तभुऽयमानः। ११

© Dharmartha Trust J&K. Digitized by eGangotri

आ। अशयत्। नि। तं। पर्यासु। बिभ्रथुः। यः। इमे इति। रोदसी इति। मही इति। समीची इति संऽई॑ची। संऽअजग्र

भीत्। तमःऽभिः। इंद्र। तं। गुहः। ये। इंद्र। यतयः। त्वा। भृगवः। ये। च। तुस्तुवुः। मम। इत्। उग्र। श्रुधि। हवं। इमाः। ते। इंद्र।

पृश्नयः। घृतं। दुहते। आऽशिरं। एनां। ऋतस्य। पिप्युषीः। याः। इंद्र। प्रऽस्वः। त्वा। आसा। गर्भं। अचक्रिरन्। परि।

धर्मऽइव। सूर्यं॥ ३२॥ त्वां। इत्। शवसः। पते। कण्वाः। उक्थेन। ववृधुः। त्वां। सुतासः। इंदवः। त्वा। इत्। इंद्र। प्रऽनी

तिषु। उत। प्रऽशस्तिः। अद्रिऽवः। यज्ञः। वितंतसाय्यः। आ। नः। इंद्र। महीं। इषं। पुरं। न। दर्षि। गोऽमतीं। उत। प्रऽजां।

सुऽवीर्यं। उत्। त्यत्। आशुऽअश्व्यं। यत्। इंद्र। नाहुषीषु। आ। अग्रे। विक्षु। प्रऽदीदयत्। अभि। व्रजं। न। तत्निषे।

सूरः। उपाकऽचक्षसं। यत्। इंद्र। मृळयासि। नः॥ ३३॥ यत्। अंग। तविषीऽयसे। इंद्र। प्रऽराजसि। क्षितीः। महा

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. न्। अपारः। ओजसा। तं। त्वा। हविष्मतीः। विशः। उप। ब्रुवते। ऊतये। उरुऽज्रयसं। इंदुऽभिः। उपऽह्वरे। गिरीणां।
३०० संऽगथे। च। नदीनां। धिया। विप्रः। अजायत। अतः। समुद्रं। उत्ऽवतः। चिकित्वान्। अव। पश्यति। यतः। विऽपानः
150 । एजति। आत्। इत्। प्रत्नस्य। रेतसः। ज्योतिः। पश्यंति। वासरं। परः। यत्। इध्यते। दिवि॥ कण्वासः। इंद्र। ते। मति
। विश्वे। वर्द्धंति। पौंस्यं। उतो इति। शविष्ठ। वृष्ण्यं॥ इमां। मे। इंद्र। सुऽस्तुतिं। जुषस्व। प्र। सु। मां। अव। उत। प्र। वर्द्ध
य। मतिं। उत। ब्रह्मण्या। वयो। तुभ्यं। प्रऽवृद्ध। वज्रिऽवः। विप्राः। अतक्ष्म। जीवसे। अभि। कण्वाः। अनूषत। आ
पः। न। प्रऽवता। यतीः। इंद्र। वनन्ऽवती। मतिः। इंद्र। उक्था। नि। वः। रथ्युः। समुद्रंऽइव। सिंधवः। अनु। त्वा। मन्युं। अ
अजरं॥ १५॥ आ। नः। [illegible] याहि। पराऽवतः। हरिऽभ्यां। हर्यताभ्यां। इमं। इंद्र। सुतं। पिब। [illegible]। वां। इत्। अव १००

© Dharmartha Trust J&K. Digitized by eGangotri

अहन्ऽतम्। आजनाः। स्तृक्तऽबर्हिषः। हवंते। वाजंऽसातये। अनु। त्वा। रोदसी इति। उभे इति। चक्रं। न। वर्त्ति। एतशं।
अनु। सुवानासः। इंदवः। मंदस्व। सु। स्वःऽनरे। तु। नः। इंद्र। शर्यणाऽवति। मत्स्व। विवस्वतः। मती। ववृधानः। उ
प। द्यवि। वृषा। वज्री। अरोरवीत्। वृत्रऽहा। सोमऽपातमः। ऽधा। ऋषिः। हि। पूर्वऽ आसि। एकः। ईशानः। ओज जाः।
सा। इंद्र। चोष्कूयसे। वसु। अस्माकं। त्वा। सुतान्। उप। वीतऽपृष्ठाः। अभि। प्रयः। शतं। वहंतु। हरयः। इमां। सु।
पूर्व्यां। धियं। मधोः। घृतस्य। पिप्युषीं। कण्वाः। उक्थेन। ववृधुः। इंद्रं। इत्। आ। विऽमहीनां। मेधे। वृणीत। मर्त्यः।
इंद्रं। सनिष्युः। ऊतये। अर्वांचं। त्वा। पुरुऽस्तुत। प्रियमेधऽस्तुता। हरी इति। सोमऽपेयाय। वक्षतः। शतं। अ
हं। तिरिंदिरे। सहस्रं। पर्शौ। आ। ददे। राधांसि। याद्वानां। त्रीणि। शतानि। अर्वतां। सहस्रा। दश। गोनां। दु

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. दुःऽपुत्राय। साम्नो। उत। आनद्व। ककुहः। दिवः। उद्गानः। चतुःऽयुजः। ददत्। श्रवसा। याद्वं। जनं॥ १८॥ प्र। यत्। वः।
१०१ त्रिऽस्तुभं। इषं। मरुतः। विप्रः। अक्षरत्। वि। पर्वतेषु। राजथ। यत्। अंग। तविषीऽयवः। यामं। शुभ्राः। अचि
ध्वं। नि। पर्वताः। अहासत। उत्। ईरयंत। वायुऽभिः। वाश्रासः। पृश्निऽमातरः। धुक्षंत। पिप्युषीं। इषं। वपंति।
101 मरुतः। मिहं। प्र। वेपयंति। पर्वतान्। यत्। यामं। यांति। वायुऽभिः। नि। यत्। यामाय। वः। गिरिः। नि। सिंध
वः। विऽधर्मणे। महे। शुष्माय। येमिरे॥ १९॥ युष्मान्। ऊं इति। नक्तं। ऊतये। युष्मान्। दिवा। हवामहे। युष्मा
प न्। प्रऽयति। अध्वरे। उत्। ऊं इति। त्ये। अरुणऽप्सवः। चित्राः। यामेभिः। ईरते। वाश्राः। अधि। स्नुना। दिवः। सृजं
ति। रश्मिं। ओजसा। पंथां। सूर्याय। यातवे। ते। भानुऽभिः। वि। तस्थिरे। इमां। मे। मरुतः। गिरं। इमं। स्तोमं। १०१

© Dharmartha Trust J&K. Digitized by eGangotri

ऋभुऽक्षणः । इमं । मे । वनत । हवं । त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु । उत्सं । कवंधं । उद्रिणं ॥ १० ॥
मरुतः । यत् । ह । वः । दिवः । सुम्नऽयंतः । हवामहे । आ । तु । नः । उप । गंतन । रुद्राः । ऋभुऽक्षणः । दमे । उत । प्रऽचे यूयं हिष्ठा सुदानवो
तसः । मदे । आ । नः । रयिं । मदऽच्युतं । पुरुऽक्षुं । विश्वऽधायसं । इयर्त । मरुतः । दिवः । अधिऽइव । यत् । गिरीणां ।
यामं । शुभ्राः । अचिध्वं । सुवानैः । मंदध्वे । इंदुऽभिः । एतावतः । चित् । एषां । सुम्नं । भिक्षेत । मर्त्यः । अदाभ्यस्य ।
मन्मऽभिः ॥ २० ॥ ये । द्रप्साःऽइव । रोदसी इति । धमंति । अनु । वृष्टिऽभिः । उत्सं । दुहंतः । अक्षितं । उत् । ऊं इति ।
स्वानेभिः । ईरते । उत् । रथैः । उत् । ऊं इति । वायुऽभिः । उत् । स्तोमैः । पृश्निऽमातरः । येन । आव । तुर्वशं । यदुं ।
येन । कण्वं । धनऽस्पृतं । राये । सु । तस्य । धीमहि । इमाः । ऊं इति । वः । सुऽदानवः । घृतं । न । पिप्युषीः । इषः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰पं॰ वह्नीनां। काण्वस्य। मन्मऽभिः। कः। नूनं। सुऽदानवः। मदथ। वृक्तऽबर्हिषः। ब्रह्मा। कः। वः। सपर्यति। २१। नहि।
३॰२ स्म। यत्। ह। वः। पुरा। स्तोमेभिः। वृक्तऽबर्हिषः। शर्द्धान्। ऋतस्य। जिन्वथ। सं। ऊंइति। त्ये। महतीः। अपः। सं।
क्षोणीइति। सं। ऊंइति। सूर्यं। सं। वज्रं। पर्वऽशः। दधुः। वि। वृत्रं। पर्वऽशः। ययुः। वि। पर्वतान्। अराजिनः। चक्रा
102 णाः। वृष्णि। पौंस्यं। अनु। त्रितस्य। युध्यतः। शुष्मं। आवन्। उत। क्रतुं। अनु। इंद्रं। वृत्रऽतूर्ये। विद्युत्ऽहस्ताः।
अभिऽद्यवः। शिप्राः। शीर्षन्। हिरण्ययीः। शुभ्राः। वि। अंजत। श्रिये। २२। उशनाः। यत्। पराऽवतः। उक्ष्णः।
रध्रं। अयातन। द्यौः। न। चक्रदत्। भिया। आ। नः। मखस्य। दावने। अश्वैः। हिरण्यपाणिऽभिः। देवासः। उ
प। गंतन। आ। यत्। एषां। पृषतीः। रथे। प्रष्टिः। वहति। रोहितः। यांति। शुभ्राः। रिणन्। अपः। सुऽसोमे। शर्यणाऽ ३०२

© Dharmartha Trust J&K. Digitized by eGangotri

वति। आर्जीके। पस्त्यऽवति। ययुः। निऽचक्रया। नरः। कदा। गच्छाथ। मरुतः। इत्था॥ विप्रं। हवमानं। मार्डीके
भिः। नाधमानं॥२३॥ यत्। इंद्रं। अजहातन। कः। वः। सखिऽत्वे। ओहते। सहो इति। सु। नः। वज्रऽहस्तैः। क कद्ध नूनं कधप्रियो
ण्वासः। अग्निं। मरुत्ऽभिः। स्तुषे। हिरण्यऽवाशीभिः। ओ इति। सु। वृष्णः। प्रऽयज्यून्। आ। नव्यसे। सुवित
य। ववृत्यां। चित्रऽवाजान्। गिरयः। चित्। नि। जिहते। पर्शानासः। मन्यमानाः। पर्वताः। चित्। नि। येमिरे। आ
अक्ष्णयाऽयावानः। वहंति। अंतरिक्षेण। पततः। धातारः। स्तुवते। वयः। अग्निः। हि। जानि। पूर्व्यः। छंदः। न। सूरः। अ ते भानुभिर्वि
र्चिषा॥२४॥ आ। नः। विश्वाभिः। ऊतिऽभिः। अश्विना। गच्छतं। युवं। दस्रा। हिरण्यवर्तनी इति हिरण्यऽवर्त २
नी। पिबतं। सोम्यं। मधु। आ। नूनं। यातं। अश्विना। रथेन। सूर्यऽत्वचा। भुजी इति। हिरण्यऽपेशसा। कवी

© Dharmartha Trust J&K. Digitized by eGangotri

प. पं. इति । गंभीरऽवेपसा । आ । यातं । नहुषः । परि । आ । अंतरिक्षात् । सुवृक्तिऽभिः । पिबाथः । अश्विना । मधु । कण्वानां ।
१०३ सवने । सुतं । आ । नः । यातं । दिवः । परि । आ । अंतरिक्षात् । अध । प्रिया । पुत्रः । कण्वस्य । वां । इह । सुसाव । सोम्यं । म
आनो यातं धु । ४ । उपऽश्रुति । अश्विना । सोमऽपीतये । स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीतिऽभिः । नरा । ५ । यत् ।
103 चित् । हि । वां । पुरा । ऋषयः । जुहूरे । अवसे । नरा । आ । यातं । अश्विना । आ । गतं । उप । इमां । सुऽस्तुतिं । मम । ६ । दिवः ।
चित् । रोचनात् । अधि । आ । नः । गंतं । स्वःऽविदा । धीभिः । वत्सऽप्रचेतसा । स्तोमेभिः । हवनऽश्रुता । किं । अन्ये । प
रि । आसते । अस्मत् । स्तोमेभिः । अश्विना । पुत्रः । कण्वस्य । वां । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् । आ । वां । वि
प्रः । इह । अवसे । अह्वत् । स्तोमेभिः । अश्विना । अरिप्रा । वृत्रहन्ऽतमा । ता । नः । भूतं । मयःऽभुवा । आ । यत् । वां । १०३

योषणा। रथं। अतिष्ठतं। वाजिनीवसू इति वाजिनीऽवसू। विश्वानि। अश्विना। युवं। प्रऽधीतानि। अगच्छतं।

।रध्या। अतः। सहस्रऽनिर्निजा। रथेन। आ। यातं। अश्विना। वत्सः। मधुऽमत्। वचः। अशंसीत्। काव्यः। कविः। वां।

।पुरुऽमन्द्रा। पुरुवसू इति पुरुऽवसू। मनोतरा। रयीणां। स्तोमं। मे। अश्विनौ। इमं। अभि। वह्नी इति। अनूषातां।

आ। नः। विश्वानि। अश्विना। धत्तं। राधांसि। अह्रया। कृतं। नः। ऋत्विऽयऽवतः। मा। नः। रीरधतं। निदे। ॰ अं यंनासत्या परावति

बेरा ॰ यः। वां। नासत्यौ। ऋषिः। गीःऽभिः। वत्सः। अवीरधत्। तस्मै। सहस्रऽनिर्निजं। इषं। धत्तं। घृतऽश्चु अतःसहस्रनि

तं।। र गा। प्र। अस्मै। ऊर्जं। घृतऽश्चुतं। अश्विना। यच्छतं। युवं। यः। वां। सुम्नाय। तुस्तवत्। वसुऽयात्। दानुनः

।पती इति। आ। नः। गन्तं। रिशादसा। इमं। स्तोमं। पुरुऽभुजा। कृतं। नः। सुऽश्रियः। नरा। इमा। दातं। अभिष्ट

© Dharmartha Trust J&K. Digitized by eGangotri

१.१०. ये। आ। वां। विश्वाभिः। ऊतिऽभिः। प्रियऽमेधाः। अहूषत। राजंतौ। अध्वराणां॥ अश्विना। यामऽहूतिषु॥०॥ मयुऽ आ नो गं तं।
३.८ भुवा। अश्विना। शंऽभुवा। युवं। यः। वां। विपन्यूइति। धीतिऽभिः। गीःऽभिः। वत्सः। अवीवृधत्। याभिः। कण्वं।
मेधऽअतिथिं। याभिः। वशं। दशऽव्रजं। याभिः। गोऽशर्यं। आवतं। ताभिः। नः। अवतं। नरा॥२०॥ याभिः। नरा।
त्रसदस्युं। आवतं। कृत्व्ये। धने। ताभिः। सु। अस्मान्। अश्विना। प्र। अवतं। वाजऽसातये। प्र। वां। स्तोमाः। सुऽ
वृक्तयः। गिरः। वर्द्धंतु। अश्विना। पुरुऽत्रा। पुरुऽस्पृहा। त्रीणि। पदानि। अश्विनोः। आविः। संति। गुहा। प
रः। कवीइति। ऋतस्य। पत्मऽभिः। अर्वाक्। जीवेभ्यः। परि॥२१॥ आ। नूनं। अश्विना। युवं। वत्सस्य। गंतं।
अवसे। प्र। अस्मै। यच्छतं। अवृकं। पृथु। छर्दिः। युयुतं। याः। अरातयः। यत्। अंतरिक्षे। यत्। दिवि। यत्। पंच। १०४

© Dharmartha Trust J&K. Digitized by eGangotri

मानुषान्।अनु।नृम्णं।तत्।धत्तं।अश्विना।ये।वां।दंसांसि।अश्विना।विप्रासः।परिऽममृशुः।एवाइत्।काण्व

स्य।बोधतं।अयं।वां।घर्मः।अश्विना।स्तोमेन।परि।सिच्यते।अयं।सोमः।मधुऽमान्।वाजिनीवसू इति वा

जिनीऽवसू।येन।वृत्रं।चिकेतथः।यत्।अप्ऽसु।यत्।वनस्पतौ।यत्।ओषधीषु।पुरुऽदंससा।कृतं।तेन।मा।

अविष्टं।अश्विना॥३०॥यत्।नासत्या।भुरण्यथः।यत्।वा।देवा।भिषज्यथः।अयं।वां।वत्सः।मतिऽभिः।न।

विंधते।हविष्मंतं।हि।गच्छथः।आ।नूनं।अश्विनोः।ऋषिः।स्तोमं।चिकेत।वामया।आ।सोमं।मधुमत्ऽत

मं।घर्मं।सिंचात्।अथर्वणि।आ।नूनं।रघुऽवर्तनिं।रथं।तिष्ठाथः।अश्विना।आ।वां।स्तोमाः।इमे।मम।

नभः।न।चुच्यवीरत।यत्।अद्य।वां।नासत्या।उक्थैः।आऽचुच्युवीमहि।यत्।वा।वाणीभिः।अश्विना।०

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. यत्।वां।कक्षीवान्।उत।यत्।विऽअश्वः।ऋषिः।यत्।वां।दीर्घऽतमाः।जुहाव।पृथी।यत्।वां।वैन्यः।सदनेषु।
१०५ एव।इत्।अतः।अश्विना।चेतयेथां॥३॥आ।यातं।छर्दिःऽपौ।उत।नः।परःऽपा।भूतं।जगत्ऽपौ।उत।नः।तनूऽपा।
वर्तिः।तोकाय।तनयाय।यातं।यत्।इंद्रेण।सऽरथं।याथः।अश्विना।यत्।वा।वायुना।भवथः।संऽओक
सा।यत्।आदित्येभिः।ऋभुऽभिः।सऽजोषसा।यत्।वा।विष्णोः।विऽक्रमणेषु।तिष्ठथः।यत्।अद्य।अश्वि
नौ।अहं।हुवेय।वाजऽसातये।यत्।पृत्ऽसु।तुर्वणे।सहः।तत्।श्रेष्ठं।अश्विनोः।अवः।आ।नूनं।यातं।
अश्विना।इमा।हव्यानि।वां।हिता।इमे।सोमासः।अधि।तुर्वशे।यदौ।इमे।कण्वेषु।वां।अथ।यत्।नास
त्या।पराके।अर्वाके।अस्ति।भेषजं।तेन।नूनं।विऽमदाय।प्रऽचेतसा।छर्दिः।वत्साय।यच्छतं॥३॥अ १०५

भुरिक्षु। ऊँ इति। प्र। देव्या। साकं। वाचा। अहं। अश्विनोः। वि। आ। वः। देवि। आ। मतिं। वि। रातिं। मर्त्येभ्यः। प्र। बोध।
उषः। अश्विना। प्र। देवि। सूनृते। महि। प्र। यज्ञऽहोतः। आनुषक्। प्र। मदाय। श्रवः। बृहत्। यत्। उषः। यासि।
भानुना। सं। सूर्येण। रोचसे। आ। ह। अयं। अश्विनोः। रथः। वर्त्तिः। याति। नृऽपाय्यं। यत्। आपीनासः। अंश
वः। गावः। न। दुहे। ऊधऽभिः। यत्। वा। वाणीः। अनूषत। प्र। देवऽयंतः। अश्विना। प्र। द्युम्नाय। प्र। शवसे। प्र। नृऽ
सह्याय। शर्मणे। प्र। दक्षाय। प्रऽचेतसा। यत्। नूनं। धीभिः। अश्विना। पितुः। योना। निऽसीदथः। यत्। वा। सु
म्नेभिः। उक्थ्या॥ ३३॥ यत्। नासत्यः। दीर्घऽप्रसद्मनि। यत्। वा। अदः। रोचने। दिवः। यत्। वा। समुद्रे। अधि। आ
ऽकृते। गृहे। अतः। आ। यातं। अश्विना। यत्। वा। यज्ञं। मनवे। संऽमिमिक्षथुः। ०। बृहस्पतिं। विश्वान्। देवा

© Dharmartha Trust J&K. Digitized by eGangotri

१.पं. ना। अहं। हुवे। इंद्राविष्णू इति। अश्विनौ। आशुऽहेषसा। स्या। नु। अश्विना। हुवे। सुऽदंससा। गमे। हूता। ययोः।
३०६ अस्ति। प्र। नः। सख्यं। देवेषु। अधि। आप्यं। ययोः। अधि। प्र। यज्ञाः। असूरे। संति। सूरयः। ता। यज्ञस्य। अध्व
रस्य। प्रऽचेतसा। स्वधाभिः। या। पिबतः। सोम्यं। मधु। यत्। अद्य। अश्विनौ। अपाक्। यत्। प्राक्। स्थः। वाजि
106 नीवसू इति वाजिनीऽवसू। यत्। द्रुह्यवि। अनवि। तुर्वशे। यदौ। हुवे। वां। अथ। मा। आ। गतं। यत्। अंतरिक्षे
पतथः। पुरुऽभुजा। यत्। वा। इमे इति। रोदसी इति। अनु। यत्। वा। स्वधाभिः। अधिऽतिष्ठथः। रथे। ०। ३५। त्वं।
अग्ने। व्रतऽपाः। असि। देवः। आ। मर्त्येषु। आ। त्वं। यज्ञेषु। ईड्यः। त्वं। असि। प्रऽशस्यः। विदथेषु। सहंसा। अ
ग्ने। रथीः। अध्वराणां। सः। त्वं। अस्मत्। अप। द्वेषः। युयोधि। जातऽवेदः। अदेवीः। अग्ने। अरातीः। अंति। ३०६

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ पं॰ मित्र्या। सन्तं। अह्वा। युज्ञं। मर्तस्य। रिपोः। न। उप। वेषि। जातऽवेदः। मर्ताः। अमर्त्यस्य। ते। भूरि। नाम। मनामहे। विप्रा म
३०७ सः। जातऽवेदसः॥३५॥ विप्रं। विप्रासः। अवसे। देवं। मर्तासः। ऊतये। अग्निं। गीःऽभिः। हवामहे। आ। ते। वत्सः।
मनः। यमत्। परमात्। चित्। सधऽस्थात्। अग्ने। त्वांऽकामया। गिरा। पुरुऽत्रा। हि। सऽदृङ्। असि। विशः।
विश्वाः। अनु। प्रऽभुः। समत्ऽसु। त्वा। हवामहे। समत्ऽसु। अग्निं। अवसे। वाजऽयन्तः। हवामहे। वाजेषु। चि
त्रऽराधसं। प्रत्नः। हि। कं। ईड्यः। अध्वरेषु। सनात्। च। होता। नव्यः। च। सत्सि। स्वां। च। अग्ने। तन्वं। पिप्रय
स्व। अस्मभ्यं। च। सौभगं। आ। यजस्व॥३६॥ इति पंचमाष्टके अष्टमोध्यायः॥ ॥शाके ३७॥५४ शोभकृ
नाम संवत्सरे दक्षिणायने वर्षर्तौ भौमवासरे भाद्रपदेमासे शुक्लपक्षे तृतीयायां तिथौ॥ ॥ ॥ ॥ ३०७

© Dharmartha Trust J&K. Digitized by eGangotri

पंचम

पत्रे

१०९

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

पं·षं श्रीगणेशायनमः॥ॐम॥यइंद्रत्रयस्त्रिंशत्पर्वतऔष्णिहंत्विंद्रःसुतेषुनारसोयदिंद्रपंचोनागोषूत्स्यभ्यस्तू
१ क्षिनौकाण्व्यायनौत्वमभिसप्तोनौष्णिहंप्रसम्राजंद्वादशेरिंविष्ठिरायाहिपंचोनाप्रगाथांतमिदंह्यधिका
द्विसमौष्णिहमश्वम्यश्विभ्यांपराग्निसूर्यानिद्भानांदेवभिरित्यादितेरदितिर्न्देइतिचद्वेद्वेतंगूर्ध्वयसमानि
शत्सोभरिराग्नेयंकाकुभंप्रगाथंहविष्लुनर्द्विपदांत्येककुप्पंक्तीत्रसदस्योर्दानस्तुतिस्तत्पूर्वेऽष्णिहकसतोबृ
हत्यावादित्येभ्यआगंतवद्विंशातिर्मारुतं॥ ॥हरिःॐम॥यः।इंद्र।सोमऽपातमः।मदः।शविष्ठ।चेतति।
येन।हंसि।नि।अत्रिणं।तं।ईमहे।येन।दशऽग्वं।अध्रिऽगुं।वेपयंतं।स्वःऽनरं।येन।समुद्रं।आविथ।तं।
ईमहे।येन।सिंधुं।महीः।अपः।रथाःऽइव।प्रऽचोदयः।पंथां।ऋतस्य।यातवे।तं।ईमहे।इमं।स्तोमं।अभिष्ट १
न

© Dharmartha Trust J&K. Digitized by eGangotri

यो। घृतं। न। पूतं। अद्रिऽवः। येन॑। नु। सद्यः। ओजसा। ववक्षिथ। इमं। जुषस्व। गिर्वणः। समुद्रःऽइव। पिन्वते।
इंद्र। विश्वाभिः। ऊतिऽभिः। ववक्षिथ॥ ३॥ यः। नः। देवः। पराऽवतः। सखिऽत्वनाय। ममहे। दिवः। न। वृष्टिं। प्र
थयन्। ववक्षिथ। ववक्षुः। अस्य। केतवः। उत। वज्रः। गभस्त्योः। यत्। सूर्यः। न। रोदसी इति। अवर्धयत्। य
दि। प्रऽवृद्ध। सत्ऽपते। सहस्रं। महिषान्। अघः। आत्। इत्। ते। इंद्रियं। महि। प्र। ववृधे। इंद्रः। सूर्यस्य। रश्मि
ऽभिः। नि। अर्शसानं। ओषति। अग्निः। वनाऽइव। ससहिः। प्र। ववृधे। इयं। ते। ऋत्वियऽवती। धीतिः। एति।
नवीयसी। सपर्यंती। पुरुऽप्रिया। मिमीते। इत्॥ ४॥ गर्भः। यज्ञस्य। देवऽयुः। क्रतुं। पुनीते। आनुषक्। स्तो
मैः। इंद्रस्य। ववृधे। मिमीते। इत्। सनिः। मित्रस्य। पप्रथे। इंद्रः। सोमस्य। पीतये। प्राची। वाशीऽइव। सुन्व

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. ते। मिमीते। इत्था। यं। विप्राः। उक्थऽवाहसः। अभिऽप्रमंदुः। आयवः। घृतं। न। पिप्ये। आसनि। ऋतस्य। यत्॥ उ
२ त। स्वऽराजे। अदितिः। स्तोमं। इंद्राय। जीजनत्। पुरुऽप्रशस्तं। ऊतये। ऋतस्य। यत्॥ अभि। वह्नयः। ऊतये।
अनूषत। प्रऽशस्तये। न। देवा। विऽव्रता। हरी इति। ऋतस्य। यत्॥ आ। यत्। सोमं। इंद्रः। विष्णुना। यत्। वा। घ।
त्रिते। आप्त्ये। यत्। वा। मरुत्ऽसु। मंदसे। सं। इंदुऽभिः। यत्। वा। शक्र। पराऽवति। समुद्रे। अधि। मंदसे।
अस्माकं। इत्। सुते। रण। सं। इंदुऽभिः। यत्। वा। असि। सुन्वतः। वृधः। [illegible] यजमानस्य। सत्ऽपते। उ
क्थे। वा। यस्य। रण्यसि। सं। इंदुऽभिः। देवंऽदेवं। वः। अवसे। इंद्रंऽइंद्रं। गृणीषणि। अध। यज्ञाय। तुर्वणे। वि।
आनशुः। यज्ञेभिः। यज्ञऽवाहसं। सोमेभिः। सोमऽपातमं। होत्राभिः। इंद्रं। वृधुः। वि। आनशुः॥ ४॥ वि। २

महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः॥

ध्वा । वस्सनि । दा । शुभे । वि । आनशुः । इंद्रं । वृत्राय । हंतवे । देवाः । सः । दधिरे । पुरः । इंद्रं । वाणीः । अनूषत । सं । ओज
से । महां । तं । महिना । वृयं । स्तोमेभिः । हवनऽश्रुतं । अर्कैः । अभि । प्र । नोनुमः । सं । ओजसे । न । यं । विवृक्तः । रोदसी
इति । न । अंतरिक्षाणि । वज्रिणं । अमात् । इत् । अस्य । तित्विषे । सं । ओजसः । यत् । इंद्र । पृतनाज्ये । देवाः । त्वा । द
धिरे । पुरः । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥ ५ ॥ यदा । वृत्रं । नदीऽवृतं । शवसा । वज्रिन् । अवधीः ॥
यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विऽचक्रमे ॥ यदा । ते । हर्यता । हरी इति । ववृधाते इति । दिवेऽदिवे ।
विश्वा । भुवनानि । येमिरे । यदा । ते । मारुतीः । विशः । तुभ्यं । इंद्र । निऽयेमिरे ॥ यदा । सूर्यं । अमुं । दिवि । शुक्रं ।
ज्योतिः । अधारयः ॥ इमां । ते । इंद्र । सुऽस्तुतिं । विप्रः । इयर्ति । धीतिऽभिः । जामिं । पदाऽइव । पिप्रतीं । प्र । अध्वरे ।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. यत्र। अस्य। धाम। मनि। प्रिये। संऽईणासः। अस्वरन्। ना। भा। यज्ञस्य। दोहना। प्र। अध्वरे। सुऽवीर्यं। सुऽअश्व्यं।
३ सुऽगव्यं। इंद्र। दद्धि। नः। होताऽइव। पूर्वऽचित्तये। प्र। अध्वरे। धाः। इंद्रः। सुतेषु। सोमेषु। क्रतुं। पुनीते। उक्थ्यं। विदे। वृ
3 धस्य। दक्षसः। महान्। हि। सः। सः। प्रथमे। विऽओमनि। देवानां। सदने। वृधः। सुऽपारः। सुश्रवःऽतमः। सं।
अप्सुऽजित्। तं। अह्वे। वाजऽसातये। इंद्रं। भराय। शुष्मिणं। भव। नः। सुम्ने। अंतमः। सखा। वृधे। इयं। ते। इंद्र।
गिर्वणः। रातिः। क्षरति। सुन्वतः। मंदानः। अस्य। बर्हिषः। वि। राजसि। नूनं। तत्। इंद्र। दद्धि। नः। यत्। त्वा। सु
न्वंतः। ईमहे। रयिं। नः। चित्रं। आ। भर। स्वःऽविदं॥ ७॥ स्तोता। यत्। ते। विऽचर्षणिः। अतिऽप्रशर्धयत्। गिरः।
वयाःऽइव। अनु। रोहते। जुषंत। यत्। प्रत्नऽवत्। जनय। गिरः। शृणुधि। जरितुः। हवं। मदेऽमदे। ववक्षिथ। सुऽ ३

© Dharmartha Trust J&K. Digitized by eGangotri

कृत्वेन । कीं । ऊंति । अस्य । सूनृतां ॥ आपः । न । प्रऽवता । यतीः ॥ अया । धिया । यः । उच्यते । पतिः ॥ दिवः । उतो इति । पतिः ।
यः । उच्यते । कृष्टीनां । ८ कः । इत्वा । वशी । नु । मुःऽवृधेः । अवत्युऽभिः । सुते । रणा । स्तुहि । श्रुतं । विप्रः ऽ चिते । हरी इति ।
यस्य । प्रऽसक्षिणा । गंता । रा । हथुषः । गृहं । नमस्विनः ॥ ॥ तूतुजानः । महेऽमते । अश्वेभिः । प्रुषितप्सुऽभिः ।
आ । याहि । यज्ञं । आशुऽभिः । शं । इत् । हि । ते । इंद्र । शविष्ठ । सत्ऽपते । रयिं । गृणत्ऽसु । धारय । श्रवः । सूरिऽ
भ्यः । अमृतं । वसुऽत्वनं । हवे । त्वा । सुरे । उत्ऽइते । हवे । मध्यंदिने । दिवः । जुषाणः । इंद्र । सप्तिऽभिः । नः । आ
गहि । आ । तु । गहि । प्र । तु । द्रव । मत्स्व । सुतस्य । गोऽमतः । तंतुं । तनुष्व । पूर्व्यं । यथा । विदा । यत् । शक्र । असि
पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् । यत् । वा । समुद्रे । अंधसः । अविता । इत् । असि ॥ ८ ॥ इंद्रं । वर्धंतु

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. नः। गिरः। इंद्रं। सुतासः। इंदवः। इंद्रे। ह। विश्वतीः। विशः। अरातिषु। तं। इत्। विप्राः। अवस्यवः। प्रवत्वतीभिः। ऊ
४ तिऽभिः। इंद्रं। क्षोणीः। अवर्धयन्। वयाःऽइव। त्रिऽकद्रुकेषु। चेतनं। देवासः। यज्ञं। अत्नत। तं। इत्। वर्धंतु। नः।
स्तोँतायते गिरः। सदाऽवृधं। अनुऽव्रतः। उक्थानि। ऋतुऽथा। दधे। शुचिः। पावकः। उच्यते। सः। अद्भुतः। नत्। इत्। रुद्र
५ स्य। चेतति। यह्वं। प्रत्नेषु। धामऽसु। मनः। यत्र। वि। तत्। दधुः। विऽचेतसः॥ १०॥ यदि। मे। सख्यं। आऽवरः। इ
मस्य। पाहि। अंधसः। येन। विश्वाः। अति। द्विषः। अतारिम। कदा। ते। इंद्र। गिर्वणः। स्तोता। भवाति। शंऽत
मः। कदा। नः। गव्ये। अश्व्ये। वसौ। दधः। उत। ते। सुऽस्तुता। हरी इति। वृषणा। वहतः। रथं। अजुर्यस्य। मदि
न्ऽतमं। यं। ईमहे। तं। ईमहे। पुरुऽस्तुतं। यह्वं। प्रत्नाभिः। ऊतिऽभिः। नि। बर्हिषि। प्रिये। सदत्। अध। द्विता। व ४

© Dharmartha Trust J&K. Digitized by eGangotri

धं स्वा । स्तु । पुरुऽस्तुता । ऋषिऽस्तुताभिः । ऊतिऽभिः । धुक्षस्व । पिप्युषीं । इषं । अव । च । नः ॥ ११ ॥ इंद्र । त्वं । अविता । इ
त् । असि । इत्था । स्तुवतः । अद्रिऽवः । ऋतात् । इयर्मि । ते । धियं । मनःऽयुजं ॥ इह । त्या । सधऽमाद्या । युजानः । सोमऽपी
तये । हरी इति । इंद्र । प्रतद्वसू इति प्रतत्ऽवसू । अभि । स्वर । अभि । स्वरंतु । ये । तव । रुद्रासः । सक्षत । श्रियं । उतो
इति । मरुत्वतीः । विशः । अभि । प्रयः । इमाः । अस्य । प्रऽतूर्तयः । पदं । जुषंत । यत् । दिवि । नाभा । यज्ञस्य । सं । द
धुः । यथा । विदे । अयं । दीर्घाय । चक्षसे । प्राचि । प्रऽयति । अध्वरे । मिमीते । यज्ञं । आनुषक् । विऽचक्ष्य ॥ १२ ॥
वृषा । अयं । इंद्र । ते । रथः । उतो इति । ते । वृषणा । हरी इति । वृषा । त्वं । शतक्रतो इति शतऽक्रतो । वृषा ।
हवः । ० । वृषा । यज्ञः । यं । इन्वसि । वृषा । हवः । ० । ववंथा । हि । प्रतिऽस्तुतिं । वृषा । हवः ॥ १३ ॥ यत् । इंद्र । अहं । यथा ।

© Dharmartha Trust J&K. Digitized by eGangotri

प·ष· त्वां।ईशीय।वस्वः।एकः।इत्।स्तोता।मे।गोऽसखा।स्यात्।शिक्षेयं।अस्मै।दित्सेयं।शचीऽपते।मनीषि
५ णे।यत्।अहं।गोऽपतिः।स्यां।धेनुः।ते।इंद्र।सूनृता।यजमानाय।सुन्वते।गां।अश्वं।पिप्युषी।दुहे।न।ते।
वर्ता।अस्ति।राधसः।इंद्र।देवः।न।मर्त्यः।यत्।दित्ससि।स्तुतः।मघं।यज्ञः।इंद्रं।अवर्धयत्।यत्।भू
मिं।वि।अवर्तयत्।चक्राणः।ओपशं।दिवि।।१४।।वावृधानस्य।ते।वयं।विश्वा।धनानि।जिग्युषः।ऊ
तिं।इंद्र।आ।वृणीमहे।वि।अंतरिक्षं।अतिरत्।मदे।सोमस्य।रोचना।इंद्रः।यत्।अभिनत्।वलं।उत्।
गाः।आजत्।अंगिरःऽभ्यः।आविः।कृण्वन्।गुहा।सतीः।अर्वांचं।नुनुदे।वलं।इंद्रेण।रोचना।दिवः।
दृळ्हानि।दृंहितानि।च।स्थिराणि।न।पराऽनुदे।अपां।ऊर्मिः।मदन्ऽइव।स्तोमः।इंद्र।अजिरऽयते। ५

© Dharmartha Trust J&K. Digitized by eGangotri

वि। ते। मदाः। अराजिषुः॥ १५॥ त्वं। हि। स्तोमऽवर्धनः। इंद्र। असि। उक्थऽवर्धनः। स्तोतॄणां। उत। भद्रऽकृ
त्। इंद्रं। इत्। केशिना। हरी इति। सोमऽपेयाय। वक्षतः। उप। यज्ञं। सुऽराधसं। अपां। फेनेन। नमुचेः। शि
रः। इंद्र। उत्। अवर्तयः। विश्वाः। यत्। अजयः। स्पृधः। मायाभिः। उत्ऽसिसृप्सतः। इंद्र। द्यां। आऽरुरुक्षतः।
अव। दस्यून्। अधूनुथाः। असुन्वां। इंद्र। संऽसदं। विषूचीं। वि। अनाशयः। सोमऽपाः। उत्ऽतरः। भव
न्॥ १६॥ तं। ऊं इति। अभि। प्र। गायत। पुरुऽहूतं। पुरुऽस्तुतं। इंद्रं। गीःऽभिः। तविषं। आ। विवासत। यस्य। द्विऽब
र्हसः। बृहत्। सहः। दाधार। रोदसी इति। गिरीन्। अज्रान्। अपः। स्वः। वृषऽत्वना। सः। राजसि। पुरुऽस्तुत।
एकः। वृत्राणि। जिघ्नसे। इंद्र। जैत्रा। श्रवस्या। च। यंतवे। तं। ते। मदं। गृणीमसि। वृषणं। पृत्ऽसु। ससहिं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ब. ऊऽइति। लोकऽकृत्नुं। अद्रिऽवः। हरिऽश्रियं। येन। ज्योतींषि। आयवे। मनवे। च। विवेदिथ। मंदानः। अस्य। बर्हि
६ षः। वि। राजसि॥१८॥ तत्। अद्य। चित्। ते। उक्थिनः। अनु। स्तुवंति। पूर्वऽथा। वृषऽपत्नीः। अपः। जय। दिवेऽदि
वे। तव। त्यत्। इंद्रियं। बृहत्। तव। शुष्मं। उत। क्रतुं। वज्रं। शिशाति। धिषणा। वरेण्यं। तव। द्यौः। इंद्र। पौंस्यं। पृ
थिवी। वर्धति। श्रवः। त्वां। आपः। पर्वतासः। च। हिन्विरे। त्वां। विष्णुः। बृहन्। क्षयः। मित्रः। गृणाति। वरुणः।
त्वां। शर्धः। मदति। अनु। मारुतं। त्वं। वृषा। जनानां। मंहिष्ठः। इंद्र। जज्ञिषे। सत्रा। विश्वा। सुऽअपत्यानि।
दधिषे॥१९॥ सत्रा। त्वं। पुरुऽस्तुत। एकः। वृत्राणि। तोशसे। न। अन्यः। इंद्रात्। करणं। भूयः। इन्वति। यत्। इं
द्र। मन्मऽशः। त्वा। नाना। हवंते। ऊतये। अस्माकेभिः। नृऽभिः। अत्र। स्वः। जय। अरं। क्षयाय। नः। महे। वि ६

© Dharmartha Trust J&K. Digitized by eGangotri

श्वा । रूपाणि । आऽविशन्ता । इंद्रं । जैत्राय । हर्षय । शचीऽपतिं ॥ १३ ॥ सम्ऽराजं । चर्षणीनां । इंद्रं । स्तोत । नव्यं । गीःऽ
भिः । नरं । नृऽसहं । मंहिष्ठं । यस्मिन् । उक्थानि । रण्यंति । विश्वानि । च । श्रवस्या ॥ अपां । अवः । न । समुद्रे । तं । सु
ऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजं । भरे । कृत्नुं । महः । वाजिनं । सनिऽभ्यः ॥ यस्य । अनूनाः । गभीराः । मदाः । उरु
रवः । तरुत्राः । हर्षुऽमंतः । शूरऽसातौ ॥ तं । इत् । धनेषु । हितेषु । अधिऽवाकाय । हवंते ॥ येषां । इंद्रः । ते । जयंति ॥
तं । इत् । च्यौत्नैः । आर्यंति । तं । कृतेभिः । चर्षणयः ॥ एषः । इंद्रः । वरिवःऽकृत् ॥ २० ॥ इंद्रः । ब्रह्मा । इंद्रः । ऋषिः ।
इंद्रः । पुरु । पुरुऽहूतः । महान् । महीभिः । शचीभिः ॥ सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुविऽकूर्मिः । एकः ।
चित् । सन् । अभिऽभूतिः ॥ तं । अर्केभिः । तं । सामऽभिः । तं । गायत्रैः । चर्षणयः ॥ इंद्रं । वर्धंति । क्षितयः ॥ प्रऽने

© Dharmartha Trust J&K. Digitized by eGangotri

१·५· तारीं [illegible] वस्यः।अह्नां।केतारं।ज्योतिः।सुमतःसु।ससफांसं।युधा।अमित्रान्।सः।नः।पप्रिः।पारयाति
८ ।स्वस्ति।नावा।पुरुऽहूतः।इंद्रः।विश्वाः।अति।द्विषः।सः।त्वं।इंद्र।वाजेभिः।दशस्य।च।गातुऽय।च।अह्ना। नः।
7 च।नः।सुम्नं।नेषि।२१।आ।याहि।सुसुम।हि।ते।इंद्र।सोमं।पिब।इमं।आ।इदं।बर्हिः।सदः।मम।आ।
त्वा।ब्रह्मऽयुजा।हरी इति।वहतां।इंद्र।केशिना।उप।ब्रह्माणि।नः।शृणु।ब्रह्माणः।त्वा।वयं।युजा।सो
मऽपां।इंद्र।सोमिनः।सुतऽवंतः।[illegible]।हवामहे।आ।नः।याहि।सुतऽवतः।अस्माकं।सुऽस्तुतीः।उप।पिब।
सु।शिप्रिन्।अंधसः।आ।ते।सिंचामि।कुक्ष्योः।अनु।गात्रा।वि।धावतु।गृभाय।जिह्वया।मधु।२२।
स्वादुः।ते।अस्तु।संऽसुदे।मधुऽमान्।तन्वे।तव।सोमः।शं।अस्तु।ते।हृदे।अयं।ऊं इति।त्वा।विऽचर्षणे।ज ८

© Dharmartha Trust J&K. Digitized by eGangotri

नीऽइव। अभि। संऽवृतः। प्र। सोमः। इंद्रं। सर्पतु। तुविऽग्रीवः। वपाऽउदरः। सुऽबाहुः। अंधसः। मदे। इंद्रः। वृ
त्राणि। जिघ्नते। इंद्र। प्र। इहि। पुरः। त्वं। विश्वस्य। ईशानः। ओजसा। वृत्राणि। वृत्रऽहन्। जहि। दीर्घः। ते। अस्तु।
अंकुशः। येन। वसु। प्रऽयच्छसि। यजमानाय। सुन्वते॥ २१॥ अयं। ते। इंद्र। सोमः। निःऽपूतः। अधि। बर्हिषि। आ।
इहि। ईं। अस्य। द्रव। पिब। शाचिऽगो इति शाचिऽगो। शाचिऽपूजन। अयं। रणाय। ते। सुतः। आखंडल। प्र। हूय
से। यः। ते। शृंगऽवृषः। नपात्। प्रऽनपात्। कुंडऽपाय्यः। नि। अस्मिन्। दध्रे। आ। मनः। वास्तोः। प
ते। ध्रुवा। स्थूणा। अंसत्रं। सोम्यानां। द्रप्सः। भेत्ता। पुरां। शश्वतीनां। इंद्रः। मुनीनां। सखा। पृदाकुऽसानुः।
यजतः। गोःऽएषणः। एकः। सन्। अभि। भूयसः। भूर्णिं। अश्वां। नयत्। तुजा। पुरः। गृभा। इंद्रं। सोमस्य। पीत

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. ये । २४ । इदं । हि । नूनं । एषां । सुम्नं । भिक्षेत । मर्त्यः । आदित्यानां । अपूर्व्यं । सवीमनि । अनर्वाणः । हि । एषां । पन्थाः ।
८ आदित्यानां । अदब्धाः । सन्ति । पायवः । सुगेऽवृधः । ० शर्म । यच्छन्तु । सः । प्रथः । यत् । ईमहे । देवेभिः । दिवि । अदिते ।
अरिष्टऽभर्मन् । आ । गहि । स्मत् । सूरिऽभिः । पुरुऽप्रिये । सुशर्मऽभिः । ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि ।
8 योतवे । अंहोः । चित् । उरुऽचक्रयः । अनेहसः । २५ । अदितिः । नः । दिवा । पशुं । अदितिः । नक्तं । अद्वयाः । अदि
तिः । पातु । अंहसः । सदाऽवृधा । उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् । सा । शंऽताति । मयः ।
करत् । अप । स्रिधः । उत । त्या । दैव्या । भिषजा । शं । नः । करतः । अश्विना । युयुयातां । इतः । रपः । अप । स्रिधः ।
शं । अग्निः । अग्निऽभिः । करत् । शं । नः । तपतु । सूर्यः । शं । वातः । वातु । अरपाः । अप । स्रिधः । अप । अमीवां । ८

© Dharmartha Trust J&K. Digitized by eGangotri

अव।त्रितं।अप।सेधत।दुःऽमतिं।आदित्यासः।युयोतन।नः।अंहसः॥२६॥युयोत।शरुं।अस्मत्।आ।आ
दित्यासः।उत।अमतिं।ऋधक्।द्वेषः।कृणुत।विश्वऽवेदसः।तत्।सु।नः।शर्म।यच्छत।आदित्याः।यत्।मुमो
चति।एनस्वंतं।चित्।एनसः।सुऽदानवः।यः।नः।कः।चित्।रिरिक्षति।रक्षःऽत्वेन।मर्त्यः।स्वैः।सः।एवैः।रिरि
षीष्ट।युः।जनः।सं।इत्।तं।अघं।अश्नवत्।दुःऽशंसं।मर्त्यं।रिपुं।यः।अस्मऽत्रा।दुःऽहनावान्।उप।द्वयुः।पा
कऽत्रा।स्थन।देवाः।हृत्ऽसु।जानीथ।मर्त्यं।उप।द्वयुं।च।अद्वयुं।च।वसवः॥२७॥आ।शर्म।पर्वतानां।आ
उत।अपां।वृणीमहे।द्यावाक्षामा।आरे।अस्मत्।रपः।कृतं।ते।नः।भद्रेण।शर्मणा।युष्माकं।नावा।वस
वः।अति।विश्वानि।दुःऽइता।पिपर्तन।तुचे।तनाय।तत्।सु।नः।द्राघीयः।आयुः।जीवसे।आदित्यासः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. सुऽमहसः। रुणोतन। सक्षः। हीऽकः। वः। अंतरः। आदित्यासः। अस्ति। मृळत। युष्मे इति। इत्। वः। अपि। स्मसि।
१ सऽजासे। बृहत्। वरूथं। मरुतां। देवं। त्रातारं। अश्विना। मित्रं। ईं। महे। वरुणं। स्वस्तये। अनेहः। मित्रा। अर्यमन्।
9 न्ऽवत्। वरुणा। शंस्यं। त्रिऽवरूथं। मरुतः। यंत। नः। छर्दिः। ये। चित्। हि। मृत्युऽबंधवः। आदित्यासः। मनवः। स्मसि।
प्र। सु। नः। आयुः। जीवसे। तिरेतन।।२०।। तं। गूर्धय। स्वःऽनरं। देवासः। देवं। अरतिं। दधन्विरे। देवऽत्रा। हव्यं।
आ। ऊहिरे। विभूतऽरातिं। विप्र। चित्रऽशोचिषं। अग्निं। ईळिष्व। यंतुरं। अस्य। मेधस्य। सोम्यस्य। सोभरे।
प्र। ईं। अध्वराय। पूर्व्यं। यजिष्ठं। त्वा। ववृमहे। देवं। देवऽत्रा। होतारं। अमर्त्यं। अस्य। यज्ञस्य। सुऽक्रतुं। ऊर्जः।
नपातं। सुऽभगं। सुऽदीतिं। अग्निं। श्रेष्ठऽशोचिषं। सः। नः। मित्रस्य। वरुणस्य। सः। अपां। आ। सुम्नं। यक्षते। १

© Dharmartha Trust J&K. Digitized by eGangotri

दिवि । यः । सम्ऽइधा । यः । आऽहुती । यः । वेदेन । ददाश । मर्तः । अग्नये । यः । नमसा । सुऽअध्वरः ॥ ५ ॥ त
स्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्निऽतमं । यशः । न । तं । अंहः । देवऽकृतं । कुतः । चन । न ।
मर्त्यऽकृतं । नशत् ॥ सुऽअग्नयः । वः । अग्निऽभिः । स्याम । सूनो इति । सहसः । ऊर्जां । पते । सुऽवीरः । त्वं ।
अस्मऽयुः । प्रऽशंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः । त्वे इति । क्षेमासः । अपि । सन्ति ।
साधवः । त्वं । राजा । रयीणां । सः । अद्धा । दाशुऽअध्वरः । अग्ने । मर्तः । सुऽभग । सः । प्रऽशंस्यः । सः । धीभिः ।
अस्तु । सनिता । यस्य । त्वं । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्ऽवीरः । सः । साधते । सः । अर्वत्ऽभिः । सनि
ता । सः । विपन्युऽभिः । सः । शूरैः । सनिता । कृतं ॥ ३ ॥ यस्य । अग्निः । वपुः । गृहे । स्तोमं । चनः । दधीत । विश्वः

© Dharmartha Trust J&K. Digitized by eGangotri

प. प. वार्यैः । हव्या । वा । वेविषत् । विषः । विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षुऽतमस्य । रातिषु । अवः ।
१० देवं । उपरिऽमर्त्यं । कृधि । वसो इति । विविदुषः । वचः ॥ यः । अग्निं । हव्यदातिऽभिः । नमःऽभिः । वा । सुऽदक्षं ।
आऽविवासति । गिरा । वा । अजिरऽशोचिषं । संऽइधा । यः । निऽशिती । दाशत् । अदितिं । धामऽभिः । अ
स्य । मर्त्यः ॥ विश्वा । इत् । सः । धीभिः । सुऽभगः । जनान् । अति । द्युम्नैः । उद्नःऽइव । तारिषत् ॥ तत् । अग्ने । द्युम्नं ।
आ । भर । यत् । ससहत् । सदने । कं । चित् । अत्रिणं । मन्युं । जनस्य । दुःऽध्यः ॥ ३१ ॥ येन । चष्टे ॰ । येन । नास
त्या । भगः । वयं । तत् । ते । शवसा । गातुवित्ऽतमाः । इंद्रत्वाऽऊताः । विधेमहि ॥ ते । घ । इत् । अग्ने । सुऽआध्यः ।
ये । त्वा । विप्र । निऽदधिरे । नृऽचक्षसं । विप्रासः । देव । सुऽक्रतुं ॥ ते । इत् । वेदिं । सुऽभग । ते । आऽहुतिं । ते । सो १०

© Dharmartha Trust J&K. Digitized by eGangotri

तुं । वृक्तेः । दिविऽतः । इळा । वाजेभिः । शिश्वुः । महत् । धनं । ये । आसते । कामं । निःऽएरिरे । भद्रः । नः । अग्निः । आऽहु
तः । भद्रा । रातिः । सुऽभग । भद्रः । अध्वरः । भद्राः । उत । प्रऽशस्तयः । भद्रं । मनः । कृणुष्व । वृत्रऽतूर्ये । येन । समत्
ऽसु । ससहः । ० । भूरि । शर्धतां । वनेम । ते । अभिष्टिऽभिः ॥ २० ॥ ईळे । गिरा । मनुःऽहितं । यं । देवाः । दूतं । अरतिं ।
ह निःऽएरिरे । यजिष्ठं । हव्यऽवाहनं । तिग्मऽजंभाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये । यः । पिंशते । सू
नृताभिः । सुऽवीर्यं । अग्निः । घृतेभिः । आऽहुतः ॥ यदि । घृतेभिः । आऽहुतः । वाशीं । अग्निः । भरते । उत् । अव
अव । च । असुरःऽइव । निःऽनिजं । यः । हव्यानि । ऐरयत । मनुःऽहितः । देवः । आसा । सुऽगंधिना । विवा
सते । वार्याणि । सुऽअध्वरः । होता । देवः । अमर्त्यः । यत् । अग्ने । मर्त्यः । त्वं । स्यां । अहं । मित्रऽमहः । अमर्त्यः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. सहसः। सूनो इति। आ। कृतः॥ ३॥ न। त्वा। रासीय। अभिऽशस्तये। वसो इति। न। पापऽत्वाय। संत्य। न।
११ मे। स्तोता। अमतिऽवा। न। दुःऽहितः। स्यात्। अग्ने। न। पापया। पितुः। न। पुत्रः। सुऽभृतः। दुरोणे। आ। देवः।
एतु। प्र। नः। हविः। तव। अहा। अग्ने। ऊतिऽभिः। नेदिष्ठाभिः। सचेय। जोषं। आ। वसो इति। सदा। देवस्य।
मर्त्यः। तव। क्रत्वा। सनेयं। तव। रातिऽभिः। अग्ने। तव। प्रशस्तिऽभिः। त्वां। इत्। आहुः। प्रऽमतिं। वसो इति।
मम। अग्ने। हर्षस्व। दातवे। मा। सः। अग्ने। तव। ऊतिऽभिः। सुऽवीराभिः। तिरते। वाजभर्मऽभिः। यस्य। त्वं।
सख्यं। आऽवरः॥ ४॥ तव। द्रप्सः। नीलऽवान्। वाशः। ऋत्वियः। इंधानः। सिष्णो इति। आ। ददे। त्वं। मु
हीनां। उषसां। असि। प्रियः। क्षपः। वस्तुषु। राजसि। तं। आ। अगन्म। सोमऽरयः। सहस्रऽमुष्कं। सुऽअभि ११

© Dharmartha Trust J&K. Digitized by eGangotri

षिं। अव। से। सं:ऽरा। जं। त्रा। सद्स्यवं। पस्या। ते। अग्ने। अन्ये। अग्नयः। उपऽक्षितः। वयाःऽइव। विपः। न।
द्युम्ना। नि। युवे। जनानां। तव। क्षत्राणि। वर्धयन्। ये। आदित्यासः। अद्रुहः। पारं। नयथ। मर्त्यं। मघोनां।
विश्वेषां। सुऽदानवः। यूयं। राजानः। कं। चित्। चर्षणिऽसहः। क्षयंतं। मानुषान्। अनु। वयं। ते। वः। वरुण। मि
त्र। अर्यमन्। स्याम। इत्। ऋतस्य। रथ्यः। अदात्। मे। पौरुऽकुत्स्यः। पंचाशतं। त्रसदस्युः। वधूनां। मंहिष्ठः।
अर्यः। सत्ऽपतिः। उत। मे। प्रयियोः। वयियोः। सुऽवास्त्वाः। अधि। तुग्वनि। तिसृणां। सप्ततीनां। श्यावः।
प्रऽनेता। भुवत्। वसुः। दियानां। पतिः॥ ३५॥ आ। गंत। मा। रिषण्यत। प्रऽस्थावानः। मा। अप। स्थात। स
ऽमन्यवः। स्थिरा। चित्। नमयिष्णवः। वीळुपविऽभिः। मरुतः। ऋभुक्षणः। आ। रुद्रासः। सुदीति

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ भिः। इषा। नः। अद्य। आ। गत। पुरुऽस्पृहः। यज्ञं। आ। सोभरीऽयवः। वि। सा। हि। रुद्रियाणां। शुष्मं। उग्रं।
१२ मरुतां। शिमीऽवतां। विष्णोः। एषस्य। मीळ्हुषां। वि। द्वीपानि। पापतन्। तिष्ठत्। दुच्छुना। उभे इति। युजं
ता। रोदसी इति। धन्वानि। ऐरत्। शुभ्रऽखादयः। यत्। एजथ। स्वऽभानवः। अच्युता। चित्। वः। अज्मन्।
12 आ। नानदति। पर्वतासः। वनस्पतिः। भूमिः। यामेषु। रेजते॥३६॥ अमाय। वः। मरुतः। यातवे। द्यौः। जी
हीते। उत्ऽतरा। बृहत्। यत्र। नरः। देदिशते। तनूषु। आ। त्वक्षांसि। बाहुऽओजसः। स्वधां। अनु। श्रियं।
नरः। महि। त्वेषाः। अमऽवंतः। वृषऽ[illegible]प्सवः। वहंते। अहुतऽप्सवः। गोभिः। वाणः। अज्यते। सोभरीणां। र
थे। कोशे। हिरण्यये। गोऽबंधवः। सुऽजातासः। इषे। भुजे। महांतः। नः। स्परसे। नु। प्रति। वः। वृषत्ऽअंज १२

© Dharmartha Trust J&K. Digitized by eGangotri

यः। वृष्णे। शर्धाय। मारुताय। भरध्वं। हव्या। वृषऽप्रयाव्ने॥ वृषणश्वेन। मरुतः। वृषऽप्सुना। रथेन। वृष-
नाभिना। आ। श्येनासः। न। पक्षिणः। वृथा। नरः। हव्या। नः। वीतये। गत॥ ३॥ समानं। अंजि। एषां। वि-
भ्राजंते। रुक्मासः। अधि। बाहुषु। दविद्युतति। ऋष्टयः। ते। उग्रासः। वृषणः। उग्रऽबाहवः। नकिः। तन-
षु। येतिरे। स्थिरा। धन्वानि। आयुधा। रथेषु। वः। अनीकेषु। अधि। श्रियः। येषां। अर्णः। न। सऽप्रथः। ना-
म। त्वेषं। शश्वतां। एकं। इत्। भुजे। वयः। न। पित्र्यं। सहः। तान्। वंदस्व। मरुतः। तान्। उप। स्तुहि। तेषां। हि-
। धुनीनां। अराणां। न। चरमः। तत्। एषां। दाना। मन्हा। तत्। एषां। सुऽभगः। सः। वः। ऊतिषु। आस। पू-
र्वासु। मरुतः। विऽउष्टिषु। यः। वा। नूनं। उत। असति॥ ३॥ यस्य। वा। यूयं। प्रति। वाजिनः। नरः। आ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. हव्या । वीतये । गथ । अभि । स्वः । द्युम्नैः । उत । वाजसातिऽभिः । सुम्ना । वः । धूतयः । नशत् । यथा । रुद्रस्य । सू-
१३ नवः । दिवः । वशंति । असुरस्य । वेधसः । युवानः । तथा । इत् । असत् । ये । च । अर्हंति । मरुतः । सुऽदान-
वः । स्मत् । मीळ्हुषः । चरंति । ये । अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वं । यूनः ।
ऊं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा । गाय । गाःऽइव । चर्कृषत् । सहाः । ये । सं-
ति । मुष्टिहाऽइव । हव्यः । विश्वासु । पृत्ऽसु । होतृषु । वृष्णः । चंद्रान् । न । सुश्रवःऽतमान् । गिरा । वंदस्व ।
मरुतः । अह ॥ ३१ ॥ गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबंधवः । रिहते । ककुभः । मिथः ।
मर्तः । चित् । वः । नृतवः । रुक्मऽवक्षसः । उप । भ्रातृऽत्वं । आ । अयति । अधि । नः । गात । मरुतः । सदा । हि । १३

© Dharmartha Trust J&K. Digitized by eGangotri

वः। आ। पि॒ऽत्वं। अ॒स्ति॒। नि॒ऽध्रुवि॑। मरु॑तः। मा। हे॒ल॒स्य॒। नः॒। आ। भे॒ष॒जस्य॑। व॒ह॒त॒। सु॒ऽदा॒न॒वः॒। यू॒यं। स॒खा॒
यः॒। स॒प्त॒यः॒। याभिः॑। सिंधुं॑। अव॑थ। याभिः॑। तूर्व॑थ। याभिः॑। द॒श॒स्यथ॑। क्रिविं॑। मयः॑। नः॒। भू॒त॒। ऊ॒तिऽभिः॑।
म॒य॒ऽभुवः॒। शि॒वाभिः॑। अ॒स॒च॒ऽद्वि॒षः॒। यत्। सिंधौ॑। यत्। असि॑क्न्यां। यत्। स॒मु॒द्रेषु॑। म॒रु॒तः॒। सु॒ऽब॒र्हि॒षः॒।
यत्। पर्व॑तेषु। भे॒ष॒जं। विश्वं॑। पश्यं॑तः। बि॒भृ॒थ॒। त॒नूषु॑। आ। तेन॑। नः॒। अधि॑। वो॒च॒त॒। क्ष॒मा। रपः॑। म॒रु॒तः॒।
आतु॑रस्य। नः॒। इष्क॑र्त। विऽह्रु॑तं। पु॒नरिति॑॥ २०॥ इति षष्ठाष्टके प्रथमोऽध्यायः॥ ॥ ॥ ॐ म॒। वय
मुध्रूनां से हुवे चित्रस्य दानस्तुतिरोस्यमाश्विनं त्रिप्रगाथादि बृहत्यनुष्टुब्बेकाद्दश्याद्येककुंमध्येज्यो
तिषीइ ककिब्वा त्रिंशा द्विश्च मनावैयश्च आग्नेयमौ हि हे हस्सखायः स्त्रचौं त्यः सौषाम्णास्य बरो दोनस्तु

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. त्रिरस्यानुष्टुप्। मा वां चतुर्विंशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रो वैश्वदेव्य उपांत्यो ह्लिगगार्भोऽभुवोः पं
१४ चाधिकाव्यश्वो वांगिरस आश्विनं विंश्याद्यावाय व्यास्तत्सूर्वा श्वलस्तोगा यज्यौस्यैक विंश्यो चवि
श्यनुष्टुब् अग्निरुक्थेद्घ्यधिका मनुर्वैवस्वतो वैश्वदेवं हप्रागाथं ये त्रिंशति पंचोपांत्या पुर उष्णिक् बभ्रु
15 दशकस्यपो वा मारीचो द्विपदं नाहि वैश्वतुष्कं पुर उष्णिग्बृहत्यनुष्टुबं त्यो यजाति श्रूनात्रेयास्त्व वो
यजमानप्रशंसा च ये स्यादिवं च दंपत्योः शिष्टा स्तदाशिषानुष्टुप् चतुष्पङ्क्त्यं तं नव व्यनुष्टुप् दश
मी पादनिचृत्॥ ॥ ॐ म्मा॥ वयं। ऊ३ति। त्वां। अपूर्व्यो। स्थूरं। नाकृ। नृ। चित्रा भरं। तनः। अव स्य वं। वा
ज्ञो। चित्रं। हवामहे। उ पात्वा। कर्मन्न्। ऊतये। सः। नः। पुरो। उग्रः। चक्राम। यः। प्रपत्। वां। इत्था। हि। अवि १५

© Dharmartha Trust J&K. Digitized by eGangotri

तारं। ववृमहे। सखायः। इंद्र। सानसिं। आ। याहि। इमे। इंदवः। अश्वऽपते। गोऽपते। उर्वराऽपते। सोमं। सोमऽप
ते। पिब। वयं। हि। त्वा। बंधुऽमंतं। अबंधवः। विप्रासः। इंद्र। येमिम। या। ते। धामानि। वृषभ। तेभिः। आ। गहि।
विश्वेभिः। सोमऽपीतये। सीदंतः। ते। वयः। यथा। गोऽश्रीते। मधौ। मदिरे। विवक्षणे। अभि। त्वां। इंद्र। नोनुमः।
॥४॥ अच्छ। च। त्वा। एना। नमसा। वदामसि। किं। मुहुः। चित्। वि। दीधयः। संति। कामासः। हरिऽवः। ददिः। त्वं।
स्मः। वयं। संति। नः। धियः। नूत्नाः। इत्। इंद्र। ते। वयं। ऊती। अभूम। न। हि। नु। ते। अद्रिऽवः। विद्म। पुरा। परी
णसः। विद्म। सखिऽत्वं। उत। शूर। भोज्यं। आ। ते। ता। वज्रिन्। ईमहे। उतो इति। समस्मिन्। आ। शिशीहि।
नः। वसो इति। वाजे। सुऽशिप्र। गोऽमति। यः। नः। इदंऽइदं। पुरा। प्र। वस्यः। आऽनिनाय। तं। ऊं इति। वः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ स्तुषे। सखाय:। इंद्रं। ऊतये। हरि:ऽअश्वं। सत्ऽपतिं। चर्षणि:ऽसहं। स:। हि। स्म। य:। अमंदत। आ। तु। न:। स:।
१५ वयति। गव्यं। अश्व्यं। स्तोतृऽभ्य:। मघऽवा। शतं॥ २॥ त्वया। ह। स्वित्। युजा। वयं। प्रति। श्वसंतं। वृषभ।
15 ब्रुवीमहि। संऽस्थे। जनस्य। गोऽमत:। जयेम। कारे। पुरुऽहूत। कारिण:। अभि। तिष्ठ। मा। दु:ऽध्य:। नृऽमि:।
वृत्रं। हन्याम। शूशुयाम। च। अवे:। इंद्र। प्र। न:। धिय:। अभ्रातृव्य:। अना। त्वं। अना। पि:। इंद्र। जनुषा।
सनात्। असि। युधा। इत्। आऽपित्वं। इच्छसे। नकि:। रेवंतं। सख्याय। विंदसे। पीयंति। ते।
सुराश्व:। यदा। कृणोषि। नदनुं। सं। ऊहसि। आत्। इत्। पिताऽइव। हूयसे। मा। ते।
अमाऽजुर:। यथा। मूरास:। इंद्र। सख्ये। त्वाऽवत:। नि। सदाम। सचा। सुते॥ ३॥ मा। ते। गो। १५

ऽदत्र। निः। अराम। राधसः। इंद्र। मा। ते। गृहामहि। दृळ्हा। चित्। अर्यः। प्र। मृश। अभि। आ। भर। न। ते। दामा
नः। आऽदभे॥ इंद्रः। वा। घ। इत्। इयत्। मघं। सरस्वती। वा। सुऽभगा। ददिः। वसु। त्वं। वा। चित्र। दाशुषे॥ चित्रः।
इत्। राजा। राजकाः। इत्। अन्यके। यके। सरस्वतीं। अनु। पर्जन्यःऽइव। ततनत्। हि। वृष्ट्या। सहस्रं। अयु
ता। ददत्॥ ॥ ओ इति। त्यं। अह्वे। आ। रथं। अद्य। दंसिष्ठं। ऊतये। यं। अश्विना। सुऽहवा। रुद्रवर्तनी इति रु
द्रऽवर्तनी। आ। सूर्यायै। तस्थथुः॥ पूर्वऽआयुषं। सुऽहवं। पुरुऽस्पृहं। भुज्युं। वाजेषु। पूर्व्यं। सचनाऽवंतं। सुम
तिऽभिः। सोभरे। विऽद्वेषसं। अनेहसं॥ देवा। नमःऽभिः। अश्विना। अर्वाचीना। सुऽअवसे। करामहे। गंता
रा। दाशुषः। गृहं॥ युवोः। रथस्य। परि। चक्रं। ईयते। ईर्मा। अन्यत्। वां। इषण्यति। अस्मान्। अच्छ। सुऽमतिः।

इह त्या पुरुभूतमा २

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. वां। शुभः। पती इति। आ। धेनुःऽइव। धावतु। आ। रथः। यः। वां। त्रिऽवंधुरः। हिरण्यऽअभीशुः। अश्विना। परि।
२६ द्यावापृथिवी इति। भूषति। श्रुतः। तेन। नासत्या। आ। गतं। प्र। दशस्यंता। मनवे। पूर्व्यं। दिवि। यवं। वृके
णा। कृषथः। ता। वां। अद्य। सुमतिऽभिः। शुभः। पती इति। अश्विना। प्र। स्तुवीमहि। उप। नः। वाजिनीवसू
16 इति वाजिनीऽवसू। यातं। ऋतस्य। पथिऽभिः। येभिः। तृक्षिं। वृषणा। त्रासदस्यवं। महे। क्षत्राय। जि
न्वथः। अयं। वां। अद्रिऽभिः। सुतः। सोमः। नरा। वृषण्वसू इति वृषण्ऽवसू। आ। यातं। सोमऽपीतये।
पिबतं। दाशुषः। गृहे। आ। हि। रुहतं। अश्विना। रथे। कोशे। हिरण्यये। वृषण्वसू इति वृषण्ऽवसू। युं
जाथां। पीवरीः। इषः। याभिः। पक्थं। अवथः। याभिः। अध्रिऽगुं। याभिः। बभ्रुं। विऽजोषसं। ताभिः। नु॥ २६

© Dharmartha Trust J&K. Digitized by eGangotri

ङ्गः। मृक्षु। सूर्यां। अश्विना। आ। गतं। भिषज्यतं। यत्। आतुरं॥ द्या। यत्। अध्रिऽगावः। अध्रिगू इत्यध्रिऽगू।
इदा। चित्। अह्नः। अश्विना। हवामहे। वयोगीःऽभिः। विपन्यवः। ताभिः। आ। यातं। वृषणा। उप। मे। ह
वं। विश्वऽप्सुं। विश्वऽवार्यं। इषा। मंहिष्ठा। पुरुऽभूतमा। नरा। याभिः। क्रिविं। ववृधुः। ताभिः। आ। गतं।
तौ। इदा। चित्। अहानां। तौ। अश्विना। वंदमानः। उप। ब्रुवे। तो ऊं इति। नमःऽभिः। ईमहे। तौ। इत्। दोषा। तौ।
उषसि। शुभः। पती इति। ता। यामन्। रुद्रवर्तनी इति रुद्रऽवर्तनी। मा। नः। मर्ताय। रिपवे। वाजिनीवसू
इति वाजिनीऽवसू। परः। रुद्रौ। अति। ख्यतं। आ। सुग्म्याय। सुग्म्यं। प्रातः। रिता। रथेन। अश्विना। वा।
सक्षणी इति। हुवे। पिताऽइव। सोभरी॥ ७॥ मनःऽजवसा। वृषणा। मदऽच्युता। मक्षुंऽगमाभिः। ऊ

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. तिऽभिः। आ। राता। त्र। चित्रा। मर्तं। अस्मे इति। अवसे। पूर्वीभिः। पुरुऽभोजसा। आ। नः। अश्वऽवत्। अश्वि
३७ ना। वर्तिः। या। स्विष्ठं। मधुऽपातमा। नरा। गोऽमत्। दस्रा। हिरण्यऽवत्। सुऽप्रावर्गं। सुऽवीर्यं। सुष्ठु। वार्यं।
17 अनाधृष्टं। रक्षस्विना। अस्मिन्। आ। वां। आऽयाने। वाजिनीवसू इति वाजिनीऽवसू। विश्वा। वामा
नि। धीमहि। ८। इळिष्व। हि। प्रतीव्यं। यजस्व। जातऽवेदसं। चरिष्णुऽधूमं। अगृभीतऽशोचिषं। दामानं।
विश्वऽचर्षणे। अग्निं। विश्वऽमनः। गिरा। उत। स्तुषे। विःऽस्पर्धसः। रथानां। येषां। आऽबाधः। ऋग्मियः। इ
षः। रक्षः। च। निः। गंभे। उपः। विदा। वह्निः। विंदते। वसु। ९। दीदिऽयुषः। वि। अजरः। तपुःऽजंभस्य। सुऽद्युतः।
गणः। श्रियः। उत। ऊं इति। तिष्ठ। सुऽअध्वरा। स्तवानः। देव्या। कृपा। अभिऽख्या। भासा। बृहता। शुशुक्व

उदस्य शोचिरस्थात् २

© Dharmartha Trust J&K. Digitized by eGangotri

भिः ॥१॥ अग्ने । याहि । सुशस्तिऽभिः । हव्या । जुह्वानः । आनुषक् । यथा । दूतः । बभूथ । हव्यऽवाहनः । अ
ग्निं । वः । पूर्व्यं । हुवे । होतारं । चर्षणीनां । तं । अया । वाचा । गृणे । तं । ऊं इति । वः । स्तुषे । यज्ञेभिः । अद्भुतऽक्र
तुं । यं । कृपा । सूदयन्त । इत् । मित्रं । न । जने । सुऽधितं । ऋतऽवनि । ऋतऽवानं । ऋतऽयवः । यज्ञस्य । सा
धने । गिरा । उपो इति । एनं । जुजुषुः । नमसः । पदे । अच्छ । नः । अंगिरःऽतमं । यज्ञा । सः । यन्तु । संऽयतः । हो
ता । यः । अस्ति । विक्षु । आ । यशःऽतमः ॥१०॥ अग्ने । तव । त्ये । अजर । इंधानासः । बृहत् । भाः । अश्वाःऽ
इव । वृषणः । तविषीऽयवः । सः । त्वं । नः । ऊर्जां । पते । रयिं । रास्व । सुऽवीर्यं । प्र । अव । नः । तोके । तनये ।
समत्ऽसु । आ । यत् । वै । ऊं इति । विश्पतिः । शितः । सुऽप्रीतः । [illegible] । मनुषः । विशि । विश्वा । इत् । अग्निः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ त्मतिः। रक्षांसि। सेधति। श्रुष्टी। अग्ने। नवस्य। मे। स्तोमस्य। वीर। विश्पते। नि। मायिनः। तपुषा। रक्ष
३८ सः। दह। न। तस्य। मायया। चन। रिपुः। ईशीत। मर्त्यः। यः। अग्नये। ददाश। हव्यदातिऽभिः॥१३॥
18 विऽअश्वः। त्वा। वसुऽविदं। उक्षण्युः। अप्रीणात्। ऋषिः। महः। राये। तं। ऊं इति। त्वा। सं। इधीमहि। उशना
। काव्यः। त्वा। नि। होतारं। असादयत्। आऽयजिं। त्वा। मनवे। जातऽवेदसं। विश्वे। हि। त्वा। सऽजोष
सः। देवासः। दूतं। अक्रत। श्रुष्टी। देव। प्रथमः। यज्ञियः। भुवः। इमं। घ। वीरः। अमृतं। दूतं। कृण्वीत। म
र्त्यः। पावकं। कृष्णऽवर्तनिं। विऽहायसं। तं। हुवेम। यतऽस्रुचः। सुऽभासं। शुक्रऽशोचिषं। विशां।
अग्निं। अजरं। प्रत्नं। ईड्यं॥ ३चा। यः। अस्मै। हव्यदातिऽभिः। आऽहुतिं। मर्तः। अविधत्। भूरि। पोषं। १८

© Dharmartha Trust J&K. Digitized by eGangotri

सः।धत्ते।वीरऽवत्।यशः।प्रथमं।जातऽवेदसं।अग्निं।यज्ञेषु।पूर्व्यं।प्रति।स्रुक्।एति।नमसा।हविष्म
ती।आभिः।विधेम।अग्नये।ज्येष्ठाभिः।व्यश्वऽवत्।मंहिष्ठाभिः।मतिऽभिः।शुक्रऽशोचिषे।नूनं।अ
र्च।विहायसे।स्तोमेभिः।स्थूरयूपऽवत्।ऋषे।वैयश्व।दम्याय।अग्नये।अतिथिं।मानुषाणां।सू
नुं।वनस्पतीनां।विप्राः।अग्निं।अवसे।प्रत्नं।ईळते॥१३॥महः।विश्वान्।अभि।सतः।अभि।हव्या
नि।मानुषा।अग्ने।नि।सत्सि।नमसा।अधि।बर्हिषि।वंस्व।नः।वार्या।पुरु।वंस्व।रायः।पुरुऽस्पृ
हः।सुऽवीर्यस्य।प्रजाऽवतः।यशस्वतः।त्वं।वरो इति।सुऽसाम्ने।अग्ने।जनाय।चोदय।सदा।वसो इ
ति।रातिं।यविष्ठ।शश्वते।त्वं।हि।सुऽप्रतूः।असि।त्वं।नः।गोऽमतीः।इषः।महः।रायः।सातिं।अग्ने।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. अपां। वृधि। अग्ने। त्वं। यशाः। असि। आ। मित्रावरुणा। वह। ऋतऽवाना। संऽराजा। पूतऽदक्षसा।
१९ ॥३४॥ सखायः। आ। शिषामहि। ब्रह्म। इन्द्राय। वज्रिणे। स्तुषे। ऊं इति। सु। वः। नृऽतमाय। धृष्णवे।
19 शवसा। हि। असि। श्रुतः। वृत्रऽहत्येन। वृत्रऽहा। मघैः। मघोनः। अति। शूर। दाशसि॥ रयिं। चित्रश्र-
वःऽतमं। निरेके। चित्। यः। हरिऽवः। वसुः। ददिः। आ। निरेकं। उत। प्रियं। इन्द्र। दर्षि। जनानां। धृषता। धृ-
ष्णो इति। स्तवमानः। आ। भर। न। ते। सव्यं। न। दक्षिणं। हस्तं। वरन्ते। आऽमुरः। न। परिऽबाधः। हरि-
वः। गोऽइष्टिषु॥१८॥ आ। त्वा। गोभिःऽइव। व्रजं। गीःऽभिः। ऋणोमि। अद्रिऽवः। आ। स्म। कामं। जरि-
आ तुः। आ। मनः। पृण। विश्वानि। विष्णुऽमनसः। धिया। नः। वृत्रहन्ऽतम। उग्र। प्रनेतरिति प्रऽनेतः। अ १९

© Dharmartha Trust J&K. Digitized by eGangotri

धि। सु। चसो इति। [illegible]ग। हि। वयां। ते। अस्य। वृत्रऽहन्। विद्याम। शूर। नव्यसः। वसो इति। स्याम। ह्। स्या। पुरुऽ
हूत। राधसः। इंद्र। यथा। हि। अस्ति। ते। अपरिऽइतं। नृतो इति। शवः। अमृक्ता। रातिः। पुरुऽहूत। दाशु
षे। आ। वृष। स्व। महां। मह। महे। नृऽतम। राधसे। दृळ्हः। चित्। दृह्य। मघऽवन्। मघत्तये॥१६॥ नु। अ
न्यत्र। चित्। अद्रिऽवः। त्वत्। नः। जग्मुः। आऽशसः। मघऽवन्। शग्धि। तव। तत्। नः। ऊतिऽभिः। नहि।
अंग। नृतो इति। त्वत्। अन्यं। विंदामि। राधसे। राये। द्युम्नाय। शवसे। च। गिर्वणः। आ। इंदुं। इंद्राय।
सिंचत। पिबाति। सोम्यं। मधु। प्र। राधसा। चोदयाते। महिऽत्वना। उपो इति। हरीणां। पतिं। दक्षं।
पृंचंतं। अब्रवं। नूनं। श्रुधि। स्तुवतः। अश्व्यस्य। नहि। अंग। पुरा। चन। जज्ञे। वीरऽतरः। त्वत्। नकिः।

© Dharmartha Trust J&K. Digitized by eGangotri

११ राया। न। एवऽथाः। न। मंदनाः। २७। आ। इत्। ऊं इति। मध्वः। मदिन्ऽतरं। सिंच। वा। अध्वर्यो इति। अंधसः।
२० एव। हि। वीरः। स्तवते। सदाऽवृधः। इंद्र। स्थातः। हरीणां। नकिः। ते। पूर्व्यऽस्तुतिं। उत। आनंश। शवसा। न। भं-
दना। तं। वः। वाजानां। पतिं। अहूमहि। श्रवस्यवः। अप्रायुऽभिः। यज्ञेभिः। ववृधेन्यं। एतो इति। नु। इंद्रं। स्तवा-
20 म। सखायः। स्तोम्यं। नरं। कृष्टीः। यः। विश्वाः। अभि। अस्ति। एकः। इत्। अगोऽरुधाय। गोऽइषे। द्युक्षाय। द-
स्म्यं। वचः। घृतात्। स्वादीयः। मधुनः। च। वोचत। २८। यस्य। अमितानि। वीर्या। न। राधः। परिऽएतवे।
ज्योतिः। न। विश्वं। अभि। अस्ति। दक्षिणा। स्तुहि। इंद्रं। व्यश्वऽवत्। अनूर्मिं। वाजिनं। यमं। अर्यः। गयं। मंह-
मानं। वि। दाशुषे। एव। नूनं। उप। स्तुहि। वैयश्व। दशमं। नवं। सुऽविद्वांसं। चर्कृत्यं। चरणीनां। वेत्थ। हि। २०

© Dharmartha Trust J&K. Digitized by eGangotri

स्निः ऽ ऋती नां। वज्रऽ हस्ता। परिऽ वृजं। अहः ऽ अहः। शुंध्युः। परिऽ पदां ऽ इव। आ। ततना। इंद्रा। अवः। आ। भद्रा। येनं।
दां। सिष्वा। कृत्वेनो। हि। ला। कुऽ सोर्या। शिश्नथः। नि। चोदय।।१०।। तं। कुं इति। त्वा। नूनं। ईं। मुहा। नव्यं। दंसिष्ठ।
सन्यसे। सः। त्वं। नः। विश्वाः। अभिऽ मातीः। सक्षणिः। यः। ऋक्षीत्र। अंहसः। मुचत। यः। वा। आर्यात्।
सप्त। सिंधुषु। वधः। दासस्य। तुविऽ नृम्ण। नीनमः। यथा। वरो इति। सुऽ साम्ने। सुनिऽ भ्यः। आ। अव
हः। रयिं। विऽ अश्वेभ्यः। सुऽ भगा। वाजिनीऽ वति। आ। नार्यस्य। दक्षिणा। विऽ अश्वान्। एतु। सोमि
नः। स्थूरं। च। राधः। शतऽ वत्। सहस्रऽ वत्। यत्। त्वा। एष। ईजानः। कुहया। कुहया। ऽ कृते। एषः।
अपः। श्रितः। वलः। गोऽ मतीं। अव। तिष्ठति।।११।। ता। वां। विश्वस्य। गोपा। देवा। देवेषु। यज्ञिया। ऋ

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. तऽवाना । यजसे । पूतऽदक्षसा । मित्रा । तना । ना । रथ्या । वरुणः । यः । च । सुऽक्रतुः । सनात् । सुऽजाता । तनया ॥
२१ धृतऽव्रता । ता । माता । विश्वऽवेदसा । असुर्याय । प्रऽमहसा । मही । जजाना । अदितिः । ऋतऽवरी । महां
21 ता । मित्रावरुणा । संऽराजा । देवौ । असुरा । ऋतऽवानौ । ऋतं । आ । घोषतः । बृहत् । नपाता । शवसः । महः ।
सूनू इति । दक्षस्य । सुक्रतू इति सुऽक्रतू । सृप्रदानू इति सृप्रऽदानू । इषः । वास्तु । अधि । क्षितः ॥२३॥ सं ।
या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः । नभस्वतीः । आ । वां । चरन्तु । वृष्टयः । अधि । या । बृहतः । दि
वः । अभि । यूथाऽइव । पश्यतः । ऋतऽवाना । संऽराजा । नमसे । हिता । ऋतऽवाना । नि । सेदतुः । सांऽराज्या
य । सुक्रतू इति सुऽक्रतू । धृतऽव्रता । क्षत्रिया । क्षत्रं । आशतुः । अक्ष्णः । चित् । गातुवित्ऽतरा । अनुल्ब २१

© Dharmartha Trust J&K. Digitized by eGangotri

णेन । वक्षसा । नि । चित्रं । मिषंतं । निःऽचिरा । नि । चिक्यतुः । उत । नः । देवी । अदितिः । उरुष्यतां । नासत्या ।
उरुष्यंतु । मरुतः । वृद्धऽशवसः ॥ २ ॥ ते । नः । नावं । उरुष्यत । दिवा । नक्तं । सुऽदानवः । अरिष्यंतः । नि । पायु
ऽभिः । सचेमहि ॥ अघ्नते । विष्णवे । वयं । अरिष्यंतः । सुऽदानवे । श्रुधि । स्वऽयावन् । सिंधो इति । पूर्वऽ
चित्तये ॥ तत् । वार्यं । वृणीमहे । वरिष्ठं । गोपयत्यं । मित्रः । यत् । पांति । वरुणः । यत् । अर्यमा ॥ उत । नः । सिं
धुः । अपां । तत् । मरुतः । तत् । अश्विना । इंद्रः । विष्णुः । मीढ्वांसः । सऽजोषसः ॥ ते । हि । स्म । वनुषः । नरः ।
अभिऽमातिं । कयस्य । चित् । तिग्मं । न । क्षोदः । प्रतिऽघ्नंति । भूर्णयः ॥ ३ ॥ अयं । एकः । इत्था । पुरु । उ
रु । चष्टे । वि । विश्पतिः । तस्य । व्रतानि । अनु । वः । चरामसि ॥ अनु । पूर्वाणि । ओक्या । साम्ऽराज्यस्य ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. सखिमा।मित्रस्य।व्रता।वरुणस्य।दीर्घऽश्रुत्।पारि।यः।रश्मिना।दिवः।अंतान्।आमसे।पृथिव्याः।उ
२२ भेइति।आ।पप्रौ।रोदसीइति।महिऽत्वा।उत।ऊंइति।स्यः।शरणो।दिवः।ज्योतिः।अयंस्त।सूर्यः।अ
ग्निः।न।शुक्रः।संऽइधानः।आऽहुतः।वचः।दीर्घऽप्रसद्मनि।ईशे।वाजस्य।गोऽमतः।ईशे।हि।पित्वः।
अविषस्य।दावने।।२४।।तत्।सूर्यः।रोदसीइति।उभेइति।दोषा।वस्तोः।उप।ब्रुवे।भोजेषु।अस्मान्।
अभि।उत्।चर।सदा।ऊर्जत्रा।उक्षण्याऽयने।रजतं।हरयाणे।रथं।युक्तं।असनाम।सुऽसामनि।ता
मे।अश्व्यानां।हरीणां।निऽतोशना।उतोइति।नु।कृत्व्यानां।नृऽवाहसा।स्मदभीशूइति।स्मत्ऽअ
भीशू।कशाऽवंता।विप्रा।नविष्ठया।मती।महः।वाजिनौ।अर्वंता।सचा।असनं।।२५।।सुऽवोः।ऊं २२

© Dharmartha Trust J&K. Digitized by eGangotri

इति। सु। रथं। हुवे। सधऽस्तुत्याय। सूरिषु। अतूर्तऽदक्षा। वृषणा। वृषण्वसू इति वृषण्ऽवसू। युवं।
वरो इति। सुऽसाम्ने। महे। तने। नासत्या। अवःऽभिः। याथः। वृषणा। वृषण्वसू इति वृषण्ऽवसू। ता।
वां। अद्य। हवामहे। हव्येभिः। वाजिनीवसू इति वाजिनीऽवसू। पूर्वीः। इषः। इषयन्तौ। अति। क्षपः।
आ। वां। वाहिष्ठः। अश्विना। रथः। यातु। श्रुतः। नरा। उप। स्तोमान्। तुरस्य। दर्शथः। श्रिये। जुहुराणा।
चित्। अश्विना। आ। मन्येथां। वृषण्वसू इति वृषण्ऽवसू। युवं। हि। रुद्रा। पर्षथः। अति। द्विषः।।२८
॥दस्रा। हि। विश्वं। आनुषक्। मक्षुऽभिः। परिऽदीयथः। धियंऽजिन्वा। मधुऽवर्णा। शुभः। पती इ-
ति। उप। नः। यातं। अश्विना। राया। विश्वऽपुषा। सह। ~~[illegible]~~ मघऽवाना। सुऽवीरौ। अन

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. पःच्युता।आ।मे।अस्य।प्रतीव्यं।इंद्रनासत्या।गतं।देवा।देवेभिः।अद्य।सचनःऽतमा।युयं।हि।वां।हवाम
२३ हे।उक्षण्यंतः।व्यश्वऽवत्।सुमतिऽभिः।उप।विप्रौ।इह।आ।गतं।अश्विना।सु।ऋषे।स्तुहि।कुवित्।ते।श्र
वतः।हवं।नेदीयसः।कूळयातः।पणीन्।उत॥२॥वैयश्वस्य।श्रुतं।नरा।उतो इति।मे।अस्य।वेदथः।
सऽजोषसा।वरुणः।मित्रः।अर्यमा।युवाऽदत्तस्य।धिष्ण्या।युवाऽनीतस्य।सूरिऽभिः।अहःऽअहः।
वृषणा।मह्यं।शिक्षतं।यः।वां।यज्ञेभिः।आऽवृतः।अधिऽवस्त्रा।वधूःऽइव।सपर्यतः।शुभे।चक्राते
इति।अश्विना।यः।वां।उरुव्यचःऽतमं।चिकेतति।नृऽपाय्यं।वर्तिः।अश्विना।परि।यातं।अस्मयू इ
त्यस्मऽयू।अस्मभ्यं।सु।वृषण्वसू इति वृषणऽवसू।आ।यातं।वर्तिः।नृऽपाय्यं।विषुद्रुहाऽइव।यज्ञं। २३

23

© Dharmartha Trust J&K. Digitized by eGangotri

ऋहत्युः। गिरा। रत्ना। याहि। इषः। वां। हवानां। स्तोमः। दूतः। हुवत्। नरा। युवाभ्यां। भूतु। अश्विना।
यत्। अदः। दिवः। अर्णवे। इषः। वा। मदथः। गृहे। श्रुतं। इत्। मे। अमर्त्या। उत। स्या। श्वेतऽयावरी।
वाहिष्ठा। वां। नदीनां। सिंधुः। हिरण्यऽवर्तनिः। स्मत्। एतया। सुऽकीर्त्या। अश्विना। श्वेतया।
धिया। वहेथे इति। शुभ्रऽयावाना। युक्ष्व। हि। त्वं। रथऽसहा। युवस्व। पोष्या। वसो इति।
आत्। नः। वायो इति। मधु। पिब। अस्माकं। सवना। आ। गहि। रशालवा। वायो इति। ऋतनः।
पते। त्वष्टुः। जामातः। अद्भुत। अवांसि। आ। वृणीमहे। त्वष्टुः। जामातरं। वयं। ईशानं। रायः।
ईमहे। सुतऽवंतः। वायुं। द्युम्ना। जना। सः। वायो इति। याहि। शिवा। आ। दिवः। वहस्व। सु। सु।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ब. अश्व्यं।वहं।स्वा।मह्ः।पृथुऽपक्षसा।रथेः।वां।हि।सुऽप्रतरः।तं।मां।नरः।सत्ऽदनेषु।हूमहे।ग्नावाणं।
२४ ना।अश्वऽपृष्ठं।मंहना।सः।त्वं।नः।देव।मनसा।वायो इति।मंदानः।अग्नियः।कृधि।वाजान्।
अपः।धियः॥३०॥अग्निः।उक्थ्यः।पुरःऽहितः।ग्रावाणः।बर्हिः।अध्वरे।ऋचा।यामि।मरुतः।
ब्रह्मणः।पतिं।देवान्।अवः।वरेण्यं।आ।पशुं।गासि।पृथिवीं।वनस्पतीन्।उषसा।नक्तं।
ओषधीः।विश्वे।च।नः।वसवः।विश्वऽवेदसः।धीनां।भूत।प्रऽअवितारः।भास्तु।नः।एतु।
अध्वरः।अग्ना।देवेषु।पूर्व्यः।आदित्येषु।प्र।वरुणे।धृतऽव्रते।मरुत्ऽसु।विश्वऽभानुषु।विश्वे।
हि।स्म।मनवे।विश्वऽवेदसः।भुवन्।वृधे।रिशादसः।अरिष्टेभिः।पायुऽभिः।विश्वऽवेदसः॥ २५

25

© Dharmartha Trust J&K. Digitized by eGangotri

यंता। नः। अवृकं। छर्दिः। आ। नः। अद्य। सऽमनसः। गंत। विश्वे। सऽजोषसः। ऋचा। गिरा। मरुतः।
देवि। अदिते। सदने। पस्त्ये। महि॥ ३॥ अभि। प्रिया। मरुतः। या। वः। अश्व्या। हव्या। मित्र। प्रऽया
थन। आ। बर्हिः। इंद्रः। वरुणः। तुराः। नरः। आदित्यासः। सदंतु। नः। वयं। वः। वृक्तऽबर्हिषः। हित
ऽप्रयसः। आनुषक्। सुतऽसोमासः। वरुण। हवामहे। मनुष्वत्। इद्धऽअग्नयः। आ। प्र। यात। म
रुतः। विष्णो इति। अश्विना। पूषन्। माकीनया। धिया। इंद्रः। आ। यातु। प्रथमः। सनिष्युऽभिः।
वृषा। यः। वृत्रऽहा। गृणे॥ वि। नः। देवासः। अद्रुहः। अच्छिद्रं। शर्म। यच्छत। न। यत्। दूरात्। वसवः।
नु। चित्। अंतितः। वरूथं। आऽदधर्षति॥ अस्ति। हि। वः। सऽजात्यं। रिशादसः। देवासः। अस्ति।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. आ च्यं।प्र।नः।पूर्व्यस्मै।सुविताय।वोचत।मक्षु।सुम्नाय।नव्यसे॥३२॥इदा।हि।वः।उपऽस्तुतिं।
२५ इदा।वामस्य।भक्तये।उप।वः।विश्वऽवेदसः।नमस्युः।आ।असृक्षि।अन्यांऽइव।उत्।ऊंऽइति।
देवंदेवंवोवसे स्यः।वः।सविता।सुऽप्रनीतयः।अस्थात्।ऊर्ध्वः।वरेण्यः।नि।द्विऽपादः।चतुःऽपादः।अर्थिनः।
25 अविश्रन्।पतयिष्णवः॥०॥देवंऽदेवं।अभिष्टये।देवंऽदेवं।हुवेम।वाजऽसातये।गृणन्तः।देव्या।
धिया॥देवासः।हि।स्म।मनवे।सऽमन्यवः।विश्वे।साकं।सऽरातयः।ते।नः।अद्य।ते।अपरं।तुचे।
तु।नः।भवन्तु।वरिवःऽविदः॥प्र।वः।शंसामि।अद्रुहः।संऽस्थे।उपऽस्तुतीनां।न।तं।धूर्तिः।वरुण।
मित्र।मर्त्यं।यः।वः।धामऽभ्यः।अविधत्॥०॥३३॥ऋते।सः।विंदते।युधः।सुऽगेभिः।याति।अ २५

© Dharmartha Trust J&K. Digitized by eGangotri

ध्वनः। अर्यमा। मित्रः। वरुणः। सऽरातयः। यं। त्रायंते। सऽजोषसः। अज्रे। चित्। अस्मै। कृणुथ। निऽ

अंचनं। दुःऽगे। चित्। आ। सुऽसरणं। एषा। चित्। अस्मात्। अशनिः। परः। नु। सा। अस्रेधंती। वि

नश्यतु। यत्। अद्य। सूर्ये। उत्ऽयति। प्रियऽक्षत्राः। ऋतं। दध। यत्। निऽम्रुचि। प्रऽबुधि। विश्वऽवे

दसः। यत्। वा। मध्यंदिने। दिवः। यत्। वा। अभिऽपित्वे। असुराः। ऋतं। यते। छर्दिः। येम। वि। दाशुषे।

वयं। तत्। वः। वसवः। विश्वऽवेदसः। उप। स्थेयाम। मध्ये। आ। यत्। अद्य। सूरे। उत्ऽइते। यत्। मध्यं

दिने। आऽतुचि। वामं। धत्थ। मनवे। विश्वऽवेदसः। जुह्वानाय। प्रऽचेतसे। संऽराजः। आ। वृणीम

हे। पुत्रः। न। बहुऽपाय्यं। अश्याम। तत्। आदित्याः। जुह्वतः। हविः। येन। वस्यः। अनशामहै॥३४॥

चैत्रहः

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. ये। त्रिंशति। त्रयः। परः। देवासः। बर्हिः। आ। असदन्। विदन्। अह। द्विता। असनन्॥ ०॥ स्मद्रातिऽसा
२६ चः। अग्नयः। पत्नीऽवंतः। वषट्ऽकृताः। ते। नः। गोपाः। अपाच्याः। ते। उदक्। ते। इत्था। न्यक्। पुरस्तात्।
26 सर्वया। विशा। यथा। वशंति। देवाः। तथा। इत्। असत्। तत्। एषां। नकिः। आ। मिनत्। अराव्णा। चन।
मर्त्यः॥ सप्तानां। सप्त। ऋष्टयः। सप्त। द्युम्नानि। एषां। सप्तो इति। अधि। श्रियः। [illegible] धिरे॥ ३५॥
बभ्रुः। एकः। विषुणः। सूनरः। युवा। अंजि। अंक्ते। हिरण्ययं। योनिं। एकः। आ। ससाद। द्योतनः।
अंतः। देवेषु। मेधिरः। वाशीं। एकः। बिभर्ति। हस्ते। आयसीं। अंतः। देवेषु। निऽध्रुविः। वज्रं॥ ०॥ आऽ मेकोबिभर्तिहस्ते
हितं। तेन। वृत्राणि। जिघ्नते। तिग्मं॥ ०॥ आयुधं। शुचिः। उग्रः। जलाषऽभेषजः। पदः। एकः। पीपाय। २६

मेकोबिभर्तिहस्ते

© Dharmartha Trust J&K. Digitized by eGangotri

तस्करः। यथा। एषः। वेद। निऽधीनां। त्रीणि। एकः। उरुऽगायः। वि। चक्रमे। यत्र। देवासः। मदंति। विऽ
भिः। द्वा। चरतः। एकया। सह। प्र। प्रवासाऽइव। वसतः। सदः। द्वा। चक्राते इति। उपऽमा। दिवि। संऽरा
जा। सर्पिरासुती इति सर्पिःऽआसुती। अर्चंतः। एके। महि। साम। मन्वत। तेन। सूर्यं। अरोचयन्।
।।३४।। नहि। वः। अस्ति। अर्भकः। देवासः। न। कुमारकः। विश्वे। सतःऽमहांतः। इत्। इति। स्तुतासः।
असथ। रिशादसः। ये। स्थ। त्रयः। च। त्रिंशत्। च। मनोः। देवाः। यज्ञियासः। ते। नः। त्राध्वं। ते। अव
त। ते। ऊं इति। नः। अधि। वोचत। मा। नः। पथः। पित्र्यात्। मानवात्। अधि। दूरं। नैष्ट। पराऽवतः। ये।
देवासः। इह। स्थन। विश्वे। वैश्वानराः। उत। अस्मभ्यं। शर्म। सऽप्रथः। गवे। अश्वाय। यच्छत।।३५।।

© Dharmartha Trust J&K. Digitized by eGangotri

प·ष· यः। यजाति। यजात्। इत्। सुनवत्। च। पचाति। च। ब्रह्मा। इत्। इंद्रस्य। चाकनत्॥ पुरोळाशं। यः। अ-
२० स्मै। सोमं। ररत। आऽशिरं। पात्। इत्। तं। शक्रः। अंहसः। तस्य। द्युऽमान्। असत्। रथः। देवऽजूतः।
27 सः। शूशुवत्। विश्वा। वन्वन्। अमित्रिया। अस्य। प्रजाऽवती। गृहे। असश्चंती। दिवेऽदिवे। इळा।
धेनुऽमती। दुहे। या। दंपती इति दंऽपती। सऽमनसा। सुनुतः। आ। च। धावतः। देवासः। नित्यया। आ-
ऽशिरा॥ ३८॥ प्रति। प्राशव्यान्। इतः। सम्यंचा। बर्हिः। आशाते इति। न। ता। वाजेषु। वायतः॥ न। दे-
वानां। अपि। ह्नुतः। सुऽमतिं। न। जुगुक्षतः। श्रवः। बृहत्। विवासतः॥ पुत्रिणा। ता। कुमारिणा। विश्वं।
आयुः। वि। अश्नुतः। उभा। हिरण्यऽपेशसा॥ वीतिऽहोत्रा। कृतद्वसू इति कृतत्ऽवसू। दशस्यंता। अ- २

© Dharmartha Trust J&K. Digitized by eGangotri

मर्ताय। कं। सं। ऊधः। रोमशं। हन्तः। देवेषु। कृणुत। दुवः। ॐ रणी। महः। नदीनां। आ। वि। ह्मोः। सचा। भुवः।
॥ ३१॥ आ। इतु। पूषा। रयिः। भगः। स्वस्ति। सर्वऽधातमः। उरुः। अध्वा। स्वस्तये। अरमतिः। अनर्वणं
। विश्वः। देवस्य। मनसा। आदित्यानां। अनेहः। इत्। यथा। नः। मित्रः। अर्यमा। वरुणः। संति। गोपाः। सु
गाः। ऋतस्य। पंथाः। अग्निं। देवं। ईळे। वसूनां। सपर्यंतः। पुरुऽप्रियं। मित्रं। न। क्षेत्रऽसाधसं। मृक्षु। दे
वःऽवतः। रथः। शूरः। वा। पृत्ऽसु। का। सु। चित्। देवानां। यः। इत्। मनः। यजमानः। इयक्षति। अभि। इत्।
अयज्वनः। भुवत्। न। यजमानः। रिष्यसि। न। सुन्वानः। न। देवऽयो। इति। देवऽयो। ॐ न। किः। तं। कर्म
णा। नशत्। न। प्र। योषत्। न। योषति। ॐ असत्। अत्र। सुऽवीर्यं। उत। त्यत्। आशुऽअश्व्यं। ॥ ४०॥

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. इतिषष्ठाष्टकेद्वितीयोध्यायः॥ ॥हरिःॐ॥ प्रकृतानित्रिंशन्मेधातिथिर्वैयंघैकोनामेध्यातिथि
२८ र्बाईतंत्रिगायत्र्यनुष्टुबंतंमेद्वयाहिब्रूनांनीपातिथिरानुष्टुभंत्रचौंत्सोगायत्रंस्तंसहस्रंवस्तुरो
28 चिषौंगिरसोपश्यन्नग्निनाचतुर्विंशालिःश्यावाश्वआश्विनंमुपरिष्टाज्ज्योतिषंपंक्तिमहाबृहती
पंक्त्यंतंमावितास्तिसप्तशाक्करंमहापंक्त्यंतंप्रेदंमहापांक्तमाद्यालिजगतीयज्ञस्यदशैंद्राग्नमग्नि
मस्तोषिनाभाकंआग्नेयंमहापांक्तंहीद्राग्नीद्वादशैंद्राग्नमंत्यात्रिष्टुप्द्वितीयाशाक्करंस्माऊषु
दशनारूपंत्वस्तभ्रास्वऊर्ध्वंनानाभात्रैष्टुभमंत्यंबार्हतंचमाश्विनंमानुष्टुभमपश्याद्दिमेत्रयस्त्रिं
शद्विरूपआंगिरसआग्नेयंतुसमिधाग्निंत्रिंशद्दशघद्विचत्वारिंशात्रिशोकआद्याग्नैंद्री॥ ॥ २८

© Dharmartha Trust J&K. Digitized by eGangotri

॥ॐ॥म।प्र।कृतानि।ऋजीषिणः।कण्वाः।इंद्रस्य।गाथया।मदे।सोमस्य।वोचत।यः।ऋबिंदं।अ
नर्शनिं।पिप्रुं।दासं।अहीशुवं।वधीत्।उग्रः।रिणन्।अपः।नि।अर्बुदस्य।विष्टपं।वर्ष्माणं।बृह
तः।तिर।कृषे।तत्।इंद्र।पौंस्यं।प्रति।श्रुताय।वः।धृषत्।तूर्णाशं।न।गिरेः।अधि।हुवे।सुशिप्रं।
ऊतये।सः।गोः।अश्वस्य।वि।व्रजं।मंदानः।सोम्येभ्यः।पुरं।न।शूर।दर्षसि॥३॥यदि।मे।ररणः।
सुते।उक्थे।वा।दधसे।चनः।आरात्।उप।स्वधा।आ।गहि।वयं।घ।ते।अपि।स्मसि।स्तोतारः।इं
द्र।गिर्वणः।त्वं।नः।जिन्व।सोमऽपाः।उत।नः।पितुं।आ।भर।संऽरराणः।अविऽक्षितं।मघऽवन्।भू
रि।ते।वसु।उत।नः।गोऽमतः।कृधि।हिरण्यऽवतः।अश्विनः।इळाभिः।सं।रभेमहि।बृबत्ऽउ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ क्थं। हवामहे। सृप्रऽकरस्नं। ऊतये। साधु। कृण्वंतं। अवसे॥ २॥ यः। सुंऽस्थे। चित्। शतऽक्रतुः। आ
२९ त्। ईं। कृणोति। वृत्रऽहा। जरितृऽभ्यः। पुरुऽवसुः॥ सः। नः। शक्रः। चित्। आ। शकत्। दानऽवान्। अंत
29 रऽआभरः। इंद्रः। विश्वाभिः। ऊतिऽभिः॥ तं। इंद्रं। अभि। गायत। आऽयंतारं। महि। स्थिरं। पृतना
सु। श्रवःऽजितं। भूरेः। ईशानं। ओजसा॥ नकिः। अस्य। शचीनां। निऽयंता। सूनृतानां। नकिः। व
क्ता। न। दात। इति॥ ३॥ न। नूनं। ब्रह्मणां। ऋणं। प्राशूनां। अस्ति। सुन्वतां। न। सोमः। अप्रता।
पपे। पन्यो। इत्। उप। गायत। पन्यो। उक्थानि। शंसत। ब्रह्म। कृणोत। पन्यो। इत्। पन्यः। आ। द
र्दिरत। शता। सहस्रा। वाजी। अवृतः। इंद्रः। यः। यज्वनः। वृधः। वि। सु। चरत। स्वधाः। अनु। कृ २९

© Dharmartha Trust J&K. Digitized by eGangotri

ष्टीनां।अत्र।आ॰ऊर्वः।इंद्र।पिब।सुतानां।पिब।स्व॰धैनवानां।उत।यः।तुग्र्ये।सचा।उत।अयं।इंद्र।यः।
तव॥४॥अति।इहि।मन्यु॰साविनं।सुसु॰वांसं।उप॰अरणे।इमं।रातं।सुतं।पिब।इहि।तिस्रः।प
रा॰वतः।इहि।पंच।जनान्।अति।धेनाः।इंद्र।अव॰चाकशत्।सूर्यः।रश्मिं।यथा।सृज।आ।त्वा।य
च्छंतु।मे।गिरः।निम्नं।आपः।न।सध्र्यक्।अध्वर्यो इति।आ।तु।हि।सिंच।सोमं।वीराय।शिप्रि
णे।भर।सुतस्य।पीतये।यः।उद्नः।फलि॰गं।भिनत्।न्यक्।सिंधून्।अव॰असृजत्।यः।गोषु।
पक्वं।धारयत्॥५॥अहन्।वृत्रं।ऋचीषमः।और्ण॰वाभं।अहीशुवं।हिमेन।अविध्यत्।अर्बुदं।
प्र।वः।उग्राय।निः॰तुरे।अषाळ्हाय।प्र॰सक्षिणे।६।यः।विश्वानि।अभि।व्रता।सोमस्य।मदे।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. अंधसः। इंद्रः। देवेषु। चेतति।०। हरी इति। हिरण्यऽकेश्या। वोळ्हां। अभि। प्रयः। हितं।०। द्या। वयं।
३० घ। त्वा। सुतऽवंतः। आपः। न। वृक्तऽबर्हिषः। पवित्रस्य। प्रऽस्रवणेषु। वृत्रऽहन्। परि। स्तोतारः।
आसते। स्वरंति। त्वा। सुते। नरः। वसो इति। निरेके। उक्थिनः। कदा। सुतं। तृषाणः। ओकः। आ।
30 गमः। इंद्र। स्वब्दीऽइव। वंसगः। कण्वेभिः। धृष्णो इति। आ। धृषत्। वाजं। दर्षि। सहस्रिणं। पि
शंगऽरूपं। मघऽवन्। विऽचर्षणे। मक्षु। गोऽमंतं। ईमहे। पाहि। गाय। अंधसः। मदे। इंद्राय। मे
ध्यऽअतिथे। यः। संऽमिश्लः। हर्योः। यः। सुते। सचा। वज्री। रथः। हिरण्ययः। यः। सुऽसव्यः।
।सुऽदक्षिणः। इनः। यः। सुऽक्रतुः। गृणे। यः। आऽकरः। सहस्रा। यः। शतऽमघः। इंद्रः। यः। पूःऽभि ३०

© Dharmartha Trust J&K. Digitized by eGangotri

त्वा ॥ आरितः ॥ ७ ॥ यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः । विभूतऽद्युम्नः । च्यवनः ।
पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः । कः । ईं । वेद । सुते । सचा । पिबंतं । कत् । वयः । दधे । अयं । यः ।
पुरः । विऽभिनत्ति । ओजसा । मंदानः । शिप्री । अंधसः । दाना । मृगः । न । वारणः । पुरुऽत्रा । चरथं ।
दधे । नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा । यः । उग्रः । सन् । अनिःऽ
स्तृतः । स्थिरः । रणाय । संस्कृतः । यदि । स्तोतुः । मघऽवा । शृणवत् । हवं । न । इंद्रः । योषति । आ । ग-
मत् । सत्यं । इत्था । वृषा । इत् । असि । वृषऽजूतिः । नः । अवृतः । वृषा । हि । उग्र । शृण्विषे । पराऽव-
ति । वृषो इति । अर्वाऽवति । श्रुतः ॥ ८ ॥ वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी । वृषा ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ रथः।मघऽवन्।वृषणा।हरी इति।वृषा।त्वं।शतक्रतो इति शतऽक्रतो।वृषा।सोता।सुनोतु।ते।वृ
३१ षन्।ऋजीपिन्।आ।भर।वृषा।दधन्वे।वृषणं।नदीषु।आ।तुभ्यं।स्थातः।हरीणां।आ।इंद्र।या
हि।पीतये।मधु।शविष्ठ।सोम्यं।नः।अयं।अछ।मघऽवा।शृणवत्।गिरः।ब्रह्म।उक्था।च।सुऽक्र
31 तुः।वहंतु।त्वा।रथेऽस्थां।आ।हरयः।रथऽयुजः।तिरः।चित्।अर्यं।सवनानि।वृत्रऽहन्।अन्ये
षां।या।शतक्रतो इति शतऽक्रतो।अस्माकं।अद्य।अंतमं।स्तोमं।धिष्व।महाऽमह।अस्माकं।ते।
सवना।संतु।शंऽतमा।मदाय।द्युक्ष।सोमऽपाः॥नहि।स्तः।तव।नो इति।मम।शास्त्रे।अ
न्यस्य।रण्यति।यः।अस्मान्।वीरः।आ।अनयत्।इंद्रः।चित्।ता।घा।नतरा।अब्रवीत्।स्त्रियाः।अशा ३१

© Dharmartha Trust J&K. Digitized by eGangotri

स्यां। मनः। उतो इति। अह। क्रतुं। रघुं। स्त्री इति। चित्। ता। घ। मदऽच्युता। मिथुना। वहतः। रथं। एव। इत्। धूः।
वृष्णः। उतऽतरा। अधः। पश्यस्व। मा। उपरि। संऽतरां। पादकौ। हर। मा। ते। कशऽप्लकौ। दृशन्। स्त्री।
हि। ब्रह्मा। बभूविथ॥ १०॥ १० हरिऽभिः। उप। कण्वस्य। सुऽस्तुतिं। दिवः। अमुष्य। शासतः। दिवं। य
य। दिवावसो इति दिवाऽवसो। आ। त्वा। ग्रावा। वदन्। इह। सोमी। घोषेण। यच्छतु। ०। अत्र। वि। नेमिः
एषां। उरां। न। धूनुते। वृकः। ०। आ। त्वा। कण्वाः। इह। अवसे। हवंते। वाजऽसातये। ०। दधामि। ते। सु
तानां। वृष्णे। न। पूर्वऽपाय्यं। ०॥ ११॥ स्मतऽपुरंधिः। नः। आ। गहि। विश्वतःऽधीः। नः। ऊतये। ०। आ
नः। याहि। महेऽमते। सहस्रऽऊते। शतऽमघ। ०। आ। त्वा। होता। मनुःऽहितः। देवऽत्रा। वक्षत्। ईड्यः। ०

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. ।आ।त्वा।मदऽच्युता।हरी इति।श्येनं।पक्षाऽइव।वक्षतः।०।आ।याहि।अर्वः।आ।परि।स्वाहा।
३२ सोमस्य।पीतये।०।१३।३।उपऽश्रुति।उक्थेषु।रण्या।इह।०।सऽरूपैः।आ।सु।नः।गहि।संऽभृ
32 तैः।संभृतऽअश्वः।०।आ।याहि।पर्वतेभ्यः।समुद्रस्य।अधि।विष्टपः।०।आ।नः।गव्यानि।अ
श्व्या।सहस्रा।शूर।दर्दृहि।०।आ।नः।सहस्रऽशः।भर।अयुतानि।शतानि।च।०।आ।यत्।
इंद्रः।च।ददृहे इति।सहस्रं।वसुऽरोचिषः।ओजिष्ठं।अश्व्यं।पशुं।यो।ऋज्राः।वातऽरंहसः।
अरुषासः।रघुऽस्यदः।भ्राजंते।सूर्याःऽइव।परा।बलस्य।रातिषु।द्रवत्ऽचक्रेषु।आशुषु।ति
ष्ठं।वनस्य।मध्ये।आ।।३३।।अग्निना।इंद्रेण।वरुणेन।विष्णुना।आदित्यैः।रुद्रैः।वसुऽभिः। ३२

© Dharmartha Trust J&K. Digitized by eGangotri

सचाऽभुवा। सऽजोषसौ। उषसा। सूर्येण। च। सोमं। पिबतं। अश्विना। विश्वाभिः। धीभिः।
भुवनेन। वाजिना। दिवा। पृथिव्या। अद्रिऽभिः। सचाऽभुवा॥ विश्वैः। देवैः। त्रिऽभिः। एकाद
शैः। इह। अत्ऽभिः। मरुत्ऽभिः। भृगुऽभिः। सचाऽभुवा॥ जुषेथां। यज्ञं। बोधतं। हवस्य। मे।
विश्वा। इह। देवौ। सवना। अव। गच्छतं॥ आ। इषं। नः। वोळ्हं। अश्विना। स्तोमं। जुषेथां। यु
वशाऽइव। कन्यनां॥ गिरः। जुषेथां। अध्वरं। जुषेथां॥४॥ हारिद्रवाऽइव। पतथः। व
ना। इत्। उप। सोमं। सुतं। महिषाऽइव। अव। गच्छथः॥ त्रिः। वर्तिः। यातं। अश्विना। हंसौऽ
इव। पतथः। अध्वगौऽइव॥ श्येनौऽइव। पतथः। हव्यऽदातये॥ पिबतं। च। तृष्णुतं। च। आ।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. चा। गच्छतं। प्रऽजां। चा। धत्तं। द्रविणं। चा। धत्तं।० ऊर्जं। नः। धत्तं। अश्विना। जयतं। चा। प्रऽस्तुतं। चा।
३३ प्रा। चुा। अवतं।० हतं। चा। शत्रून्। यतं। चा। मित्रिणः।०॥१५॥ मित्राऽवरुणऽवंतौ। उत। धर्मऽवं
33 ता। मरुत्वंता। जरितुः। गच्छथः। हवं।० आदित्यैः। यातं। अश्विना। अंगिरस्वंतौ। उत। विष्णुऽवं
ता।० ऋभुऽमंता। वृषणा। वाजऽवंता।० ब्रह्म। जिन्वतं। उत। जिन्वतं। धियः। हतं। रक्षांसि। से
धतं। अमीवाः।० सोमं। सुन्वतः। अश्विना। क्षत्रं।० नॄन्।० धेनूः। विशः।०॥१६॥ अत्रेःऽइव।
शृणुतं। पूर्व्यऽस्तुतिं। श्यावऽअश्वस्य। सुन्वतः। मदऽच्युता।० अश्विना। तिरःऽअन्ह्यं। स
र्गान्ऽइव। सृजतं। सुऽस्तुतीः। उप।० रश्मीन्ऽइव। यच्छतं। अध्वरान्। उप।० अर्वाक्। रथं। ३३

© Dharmartha Trust J&K. Digitized by eGangotri

नि।युछतं।०अवस्युः।वां।अहं।ऊं इवे।धत्तं।रत्नानि।दाशुषे॥नमःऽवाके।प्रऽस्थिते।अध्वरे।नरा।
विवक्षणस्य।पीतये॥०स्वाहाऽकृतस्य।तृंपतं।सुतस्य।देवौ।अंधसः॥३७॥अविता।असि।
सुन्वतः।वृक्तऽबर्हिषः।पिब।सोमं।मदाय।कं।शतक्रतो इति शतऽक्रतो।यं।ते।भागं।अधारय
न्।विश्वाः।सेहानः।पृतनाः।उरु।ज्रयः।सं।अप्सुऽजित्।मरुत्वान्।इंद्र।सत्ऽपते॥अव।स्तो
तारं।मघऽवन्।अव।त्वां॥०ऊर्जा।देवान्।अवसि।ओजसा।त्वां॥०जनिता।दिवः।जनिता।पृ
थिव्याः॥०जनिता।अश्वानां।जनिता।गवां।असि॥०अत्रीणां।स्तोमं।अद्रिऽवः।महः।कृधि॥०
श्यावऽअश्वस्य।सुन्वतः।तथा।शृणु।यथा।अशृणोः।अत्रेः।कर्माणि।कृण्वतः।प्र।त्रसदस्युं।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. आविथ। त्वं। एकः। इत्। नृऽसह्ये। इंद्र। ब्रह्माणि। वर्धयन्॥७॥ प्र। इदं। ब्रह्म। वृत्रऽतूर्येषु। आवि
३४ थ। प्र। सुन्वतः। शचीऽपते। इंद्र। विश्वाभिः। ऊतिऽभिः। माध्यंदिनस्य। सवनस्य। वृत्रऽहन्। अ
नेद्य। पिब। सोमस्य। वज्रिऽवः। सेहानः। उग्र। पृतनाः। अभि। द्रुहः। ०। एकऽराट्। अस्य। भुवन
स्य। राजसि। ०। सऽस्थावाना। यवयसि। त्वं। एकः। इत्। ०। क्षेमस्य। च। प्रऽयुजः। च। त्वं। ईशि
षे। ०। क्षत्राय। त्वं। अवसि। न। त्वं। आविथ। ०। श्यावऽअश्वस्य। रेभतः। ०। क्षत्राणि। वर्धयन्।
॥७॥ यज्ञस्य। हि। स्थः। ऋत्विजा। सस्नी इति। वाजेषु। कर्मसु। इंद्राग्नी इति। तस्य। बोध
तं। तोशासा। रथऽयावाना। वृत्रऽहना। अपराऽजिता। ०। इदं। वां। मदिरं। मधु। अधुक्षन्। ३५

© Dharmartha Trust J&K. Digitized by eGangotri

अद्रिऽभिः।नरः।०।जुषेथां।यज्ञं।इष्टये।सुतं।सोमं।सधस्तुती इति सधऽस्तुती।इंद्राग्नी इति।आ।
गतं।नरा।इमा।जुषेथां।सवना।येभिः।हव्यानि।ऊहथुः।०।इमां।गायत्रऽवर्तनिं।जुषेथां।सुऽस्तु
तिं।मम।०।२०।प्रातर्यावऽभिः।आ।गतं।देवेभिः।जेन्यावसू इति।इंद्राग्नी इति।सोमऽपीतये।
श्यावऽअश्वस्य।सुन्वतः।अत्रीणां।शृणुतं।हवं।०।एवा।वां।अह्वे।ऊतये।यथा।अहुवंत।मेधि
राः।०।आ।अहं।सरस्वतीऽवतोः।इंद्राग्न्योः।अवः।वृणे।याभ्यां।गायत्रं।ऋच्यते॥२१॥अग्निं।
अस्तोषि।ऋग्मियं।अग्निं।ईळा।यजध्यै।अग्निः।देवान्।अनक्तु।नः।उभे इति।हि।विदथे इति।क
विः।अंतरिति।चरति।दूत्यं।नभंतां।अन्यके।समे।नि।अग्ने।नव्यसा।वचः।तनूषु।शंसं।एषां।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. नि।अरातीःररर्य्णोः।विश्वाः।अर्यः।अरातीः।इतः।युछंतु।आऽमुरः।०अग्ने।मन्मानि।तुभ्यं।कं।
३५ घृतं।न।जुह्वे।आसनि।सः।देवेषु।प्र।चिकिद्धि।त्वं।हि।असि।पूर्व्यः।शिवः।दूतः।विवस्वतः।०तत्
35 त्ऽतत्।अग्निः।वयः।दधे।यथाऽयथा।कृपण्यति।ऊर्जः।आऽहुतिः।वसूनां।शं।च।योः।च।म
यः।दधे।विश्वस्य।देवऽहूत्यै।०सः।चिकेत।सहीयसा।अग्निः।चित्रेण।कर्मणा।सः।होता।
शश्वतीनां।दक्षिणाभिः।अभिऽवृतः।इनोति।च।प्रतीव्यं।०।२२।अग्निः।जाता।देवानां।अग्निः।
वेद।मर्तानां।अपीच्यं।अग्निः।सः।द्रविणःऽदाः।अग्निः।द्वारा।वि।ऊर्णुते।सुऽआहुतः।नवीयसा।
०अग्निः।देवेषु।संऽवसुः।सः।विक्षु।यज्ञियासु।आ।सः।मुदा।काव्या।पुरु।विश्वं।भूमऽइव।पुष्य ३५

© Dharmartha Trust J&K. Digitized by eGangotri

नि। देवः। देवेषु। यज्ञियः॥ ०॥ यः। अग्निः। सप्तऽमानुषः। श्रितः। विश्वेषु। सिंधुषु॥ तं। आ। अगन्म। त्रिऽ
पस्त्यं। मंधातुः। दस्युहन्ऽतमं। अग्निं। यज्ञेषु। पूर्व्यं॥ ०॥ अग्निः। त्रीणि। त्रिऽधातूनि। आ। क्षेति।
विदथा। कविः॥ सः। त्रीन्। एकादशान्। इह। यक्षत्। च। पिप्रयत्। च। नः। विप्रः। दूतः। परिऽकृतः॥
०॥ त्वं। नः। अग्ने। आयुषु। त्वं। देवेषु। पूर्व्य। वस्वः। एकः। इरज्यसि॥ त्वां। आपः। परिऽस्रुतः। परि। यंति।
स्वऽसेतवः॥ ०॥ २३॥ इंद्राग्नी इति। युवं। सु। नः। सहंता। दासथः। रयिं। येन। दृळ्हा। सऽमत्ऽसु। आ।
वीळु। चित्। सहिषीमहि। अग्निः। वनाऽइव। वाते। इत्॥ ०॥ नहि। वां। वव्रयामहे। अथ। इंद्रं। इत्। यजा
महे। शविष्ठं। नृणां। नरं॥ सः। नः। कदा। चित्। अर्वता। आ। गमत्। आ। वाजऽसातये। गमत्। आ। मेधऽ

© Dharmartha Trust J&K. Digitized by eGangotri

॥

१.५. सोनयो॥ना॥हि॥मध्यं॥मराणां॥इंद्राग्नी इति॥अधिऽक्षितः॥तौ॥ऊं इति॥कविऽरुता॥कवी इति॥
३६ पृछ्यमाना॥सखिऽयते॥सं॥धीतं॥अश्नुतं॥नरा॥अभि॥अर्च॥नभाकऽवत्॥इंद्राग्नी इति॥
36 यज्ञसा॥गिरा॥ययोः॥विश्वं॥इदं॥जगत्॥इयं॥द्यौः॥पृथिवी॥मही॥उपऽस्थे॥बिभृतः॥वसु॥
माव्रसा॥नि॥नभाकऽवत्॥इंद्राग्निऽभ्यां॥इरज्यत॥या॥सप्तऽबुध्नं॥अर्णवं॥जिह्मऽबारं॥अप
ऊर्णुतः॥इंद्रः॥ईशानः॥ओजसा॥अपि॥रथ्या॥पुराणऽवत्॥प्रतनेःऽइव॥गुष्पितं॥ओजः॥दास
स्या॥इदं॥मयाव॥यं॥नत्॥अस्य॥संऽस्मतं॥वसु॥इंद्रेण॥वि॥भुजे॥मुहि॥रघा॥यत्॥इंद्राग्नी इति॥
जना॥इमो॥विऽक्षयंतां॥नो॥गिरा॥अस्माकेभिः॥नृऽभिः॥वयं॥ससह्याम॥पृतन्यतः॥वनु ३६

© Dharmartha Trust J&K. Digitized by eGangotri

याम। वनुष्यतः। ०या। नु। भ्वेतो। अवः। दिवः। उतःऽचरीतः। उप। सुऽभिः। इंद्राग्न्योः। अनु। व्रतं। उहाना। यं

ति। सिंधवः। या। न्। सीं। बंधात्। अमुंचतां। वपूर्वीः। ते। इंद्र। उपऽमान यः। पूर्वीः। उता। प्रऽशस्त यः। स्तुनो

इति। हिन्वस्य। हरिऽवः। वस्वः। वीरस्य। आऽपृचेः। याः। नु। साधंता। नः। धियः। ०। तां। शिशीता। सुवृक्ति

ऽभिः। त्वेषं। सत्वानं। ऋग्मियं। उतो इति। नु। चित्। यः। ओजसा। शुष्णस्य। आंडानि। भेदति। जेषत्

स्वःऽवतीः। अपः। ०। तं। शिशीता। सुऽअध्वरं। सत्यं। सत्वानं। ऋत्वियं। ०। ओ। हते। आंडा। शुष्णस्य।

भेदति। अजैः। स्वःऽवतीः। अपः। ०। एव। इंद्राग्निऽभ्यां। पितृऽवत्। नवीयः। मंधातृऽवत्। अंगिर

स्वत्। अवाचि। त्रिऽधातुना। शर्मणा। पातं। अस्मान्। ०। २५। अस्मै। ॐ इति। सुऽप्रऽभृतये। वह

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ णाय। मरुत्ऽभ्यः। अर्च। विदुःऽतरेभ्यः। यः। धीता। मानुषाणां। पश्वः। गाःऽइव। रक्षति। ०। तं। ऊं इति।
३० सु। समना। गिरा। पितॄणां। च। मन्मऽभिः। नाभाकस्य। प्रशस्तिऽभिः। यः। सिन्धूनां। उप। उत्ऽअ
37 ये। सप्तऽस्वसा। सः। मध्यमः। ०। सः। क्षपः। परि। सस्वजे। नि। उस्राः। मायया। दधे। सः। विश्वं।
परि। दर्शतः। तस्य। वेनीः। अनु। व्रतं। उषः। तिस्रः। अवर्धयन्। ०। यः। ककुभः। निऽधारयः। पृथि
व्यां। अधि। दर्शतः। सः। माता। पूर्व्यं। पदं। तत्। वरुणस्य। सप्त्यं। सः। हि। गोपाःऽइव। इर्यः। ०। यः।
धर्ता। भुवनानां। यः। उस्राणां। अपीच्या। वेद। नामानि। गुह्या। सः। कविः। काव्या। पुरु। रूपं।
द्यौःऽइव। पुष्यति। ०। रधा। यस्मिन्। विश्वानि। काव्या। चक्रे। नाभिःऽइव। श्रिता। त्रितं। जूती। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

सपर्यत।व्रजे।गावः।न।सम्ऽयुजे।युजे।अश्वान्।अयुक्षत।०।यः।आसु।अक्तुः।आऽशये।विश्वा।जा
निऽएषां।परिऽधामानि।मर्मृशत्।वरुणस्य।पुरः।गये।विश्वे।देवाः।अनु।व्रतं।०।सः।समुद्रः।अ
पीच्यः।तुरः।द्यांऽइव।रोहति।नि।यत्।आसु।यजुः।दधे।सः।मायाः।अर्चिना।अस्तृणात्।ना। पदा।
कं।आ।अरुहत्।०।यस्य।श्वेता।विऽचक्षणा।तिस्रः।भूमीः।अधिऽक्षितः।त्रिः।उत्ऽतराणि।प
प्रुः।वरुणस्य।ध्रुवं।सदः।सः।सप्तानां।इरज्यति।०।यः।श्वेतान्।अधिऽनिर्निजः।चक्रे।कृष्णा
न्।अनु।व्रता।सः।धाम।पूर्व्यं।ममे।यः।स्कंभेन।विरोदसी इति।अजः।न।द्यां।अधारयत्।
०।ऽ०।अस्तभ्नात्।द्यां।असुरः।विश्वऽवेदाः।अमिमीत।वरिमाणं।पृथिव्याः।आ।असीदत्

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. त्वा। विश्वा। भुवनानि। सम्ऽराट्। विश्वा। इत्था। तानि। वरुणस्य। व्रतानि। एव। वन्दस्व। वरुणं। बृहन्तं। न
३८ मस्य। धीरं। अमृतस्य। गोपां। सः। नः। शर्म। त्रिऽवरूथं। वि। यंसत्। पातं। नः। द्यावापृथिवी इति।
उपऽस्थे। इमां। धियं। शिक्षमाणस्य। देव। क्रतुं। दक्षं। वरुण। सं। शिशाधि। यया। अति। विश्वा। दु
ःऽइता। तरेम। सुऽतर्माणं। अधि। नावं। रुहेम। आ। वां। ग्रावाणः। अश्विना। धीभिः। विप्राः। अ
चुच्यवुः। नासत्या। सोमऽपीतये। यथा। वां। अत्रिः। अश्विना। गीःऽभिः। विप्रः। अजोहवीत्। न
रा। इमा। विप्रस्य। वेधसः। अग्नेः। अस्तृतऽयज्वनः। गिरः। स्तोमासः। ईरते। अस्मै। ते। प्र
तिऽहर्यते। जातऽवेदः। विऽचर्षणे। अग्ने। जनामि। सुऽस्तुतिं। आ। ते। काःऽइव। वाघा। इत्था। अह। ति ३८

© Dharmartha Trust J&K. Digitized by eGangotri

ग्माः। अग्ने। तव। त्विषः। दत्ऽभिः। वना। नि। बप्सति। हरयः। धूमऽकेतवः। वातऽजूताः। उप। द्यवि। यतन्ते।
वृथक्। अग्नयः। एते। त्ये। वृथक्। अग्नयः। इद्धासः। सं। अदृक्षत। उषसांऽइव। केतवः॥ २९॥
कृष्णा। रजांसि। पत्सुतः। प्रऽयाने। जातऽवेदसः। अग्निः। यत्। रोधति। क्षमि। धासिं। कृण्वानः।
ओषधीः। बप्सत्। अग्निः। न। वायति। पुनः। यन्। तरुणीः। अपि। जिह्वाभिः। अह। नंनमत्। अ
र्चिषा। जंजणाऽभवन्। अग्निः। वनेषु। रोचते। अप्ऽसु। अग्ने। सधिः। तव। [illegible]। सः। ओषधीः। अ
नु। रुध्यसे। गर्भे। सन्। जायसे। पुनः। इति। उत्। अग्ने। तव। तत्। घृतात्। अर्चिः। रोचते। आऽ
हुतं। निंसानं। जुह्वः। मुखे॥ ३०॥ उक्षऽअन्नाय। वशाऽअन्नाय। सोमऽपृष्ठाय। वेधसे।

© Dharmartha Trust J&K. Digitized by eGangotri

पू.प. स्तोमैः। विधेम। अग्नये। उत। त्वा। नमसा। वयं। होतः। वरेण्यक्रतो इति वरेण्यऽक्रतो। अग्ने। समित्ऽ
३९ भिः। ईमहे। उत। त्वा। भृगुऽवत्। शुचे। मनुष्वत्। अग्ने। आऽहुत। अंग्निस्वत्। हवामहे। त्वं। हि। अ २
३९ ग्ने। अग्निना। विप्रः। विप्रेण। सन्। सता। सखा। सख्या। समिऽध्यसे। सः। त्वं। विप्राय। दाशुषे।
रयिं। देहि। सहस्रिणं। अग्ने। वीरऽवतीं। इषं।। ३।। अग्ने। भ्रातः। इति। सहःऽकृत। रोहित्ऽअश्व।
शुचिऽव्रत। इमं। स्तोमं। जुषस्व। मे। उत। त्वा। अग्ने। मम। स्तुतः। वाश्राय। प्रतिऽहर्यते। गोःऽस्यं।
गावःऽइव। आशत। तुभ्यं। ताः। अंगिरःऽतम। विश्वाः। सुऽक्षितयः। पृथक्। अग्ने। कामाय। ये
मिरे। अग्निं। धीभिः। मनीषिणः। मेधिरासः। विपःऽचितः। अद्मऽसद्याय। हिन्विरे। तं। त्वां। ३९

© Dharmartha Trust J&K. Digitized by eGangotri

अऽश्वेषु। वाजिनं। तन्वानाः। अग्निं। अध्वरं। वह्निं। होतारं। ईळते। ॥३॥ गा। आऽकृतः। अग्निः। विऽभ्राजे
ते। घृतेः। इमं। नः। शृणवत्। हवं। तं। त्वा। वयं। हवामहे। शृण्वंतं। जातऽवेदसं। अग्ने। घ्नंतं। अप। द्वि
षः। विशां। राजानं। अद्भुतं। अधिऽअक्षं। धर्मणां। इमं। अग्निं। ईळे। सः। ऊं इति। श्रवत्। अग्निं। वि
श्वाऽयुऽवेपसं। मर्यं। न। वाजिनं। हितं। सप्तिं। न। वाजयामसि। ॥३॥ घ्नन्। मृध्राणि। अप। द्विषः।
दहन्। रक्षांसि। विश्वहा। अग्ने। तिग्मेन। दीदिहि। यं। त्वा। जनासः। इंधते। मनुष्वत्। अग्निरःऽत
म। अग्ने। सः। बोधि। मे। वचः। यत्। अग्ने। दिविऽजाः। असि। अप्सुऽजाः। वा। सहसःऽकृत। तं। त्वा। गीःऽ
भिः। हवामहे। तुभ्यं। घ। इत्। ते। जनाः। इमे। विश्वाः। सुऽक्षितयः। पृथक्। धासिं। हिन्वंति। अत्तवे।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. ०।अह्ना।विश्वानरः।चक्षसः।लरैतः।स्याम।दुःऽगहा॥३४॥अग्निं।मन्द्रं।पुरुऽप्रियं।शीरं।पावकऽशोचि
५० षं।हृत्ऽभिः।मन्द्रेभिः।ईमहे।सः।त्वं।अग्ने।विभाऽवसुः।स्रुजन्।सूर्यः।न।रश्मिऽभिः।शर्धन्।तमां
सि।जिघ्नसे।तत्वा।ते।सहस्वः।ईमहे।दात्रं।यत्।न।उपऽदस्यति।त्वं।अग्ने।वायीं।वसु॥३५॥सं।इ
धा।अग्निं।दुवस्यत।घृतैः।बोधयत।अतिथिं।आ।अस्मिन्।हव्या।जुहोतन।अग्ने।स्तोमं।जुषस्व।
मा।वर्धस्व।अनेन।मन्मना।प्रति।सुऽउक्तानि।हर्य।नः।अग्ने।दूतं।पुरः।दधे।हव्यऽवाहं।उप।ब्रु
वे।देवान्।आ।सादयात्।इह।उत।त्वा।बृहन्तः।अर्चयः।सं।इधानस्य।दीदिऽवः।अग्ने।शुक्रासः।ई
रते।उप।त्वा।जुह्वः।मम।घृताचीः।यन्तु।हर्यत।अग्ने।हव्या।जुषस्व।नः॥३६॥मन्द्रं।होतारं।ऋत्वि ५०

© Dharmartha Trust J&K. Digitized by eGangotri

जो। चित्रऽभानुं। विभाऽवसुं॥ ० प्रत्नं। होतारं। ईड्यं। जुष्टं। अग्निं। कविऽक्रतुं। अध्वराणां। अभिऽश्रियं। जु
षाणः। अंगिरःऽतम। इमा। हव्यानि। आनुषक्। अग्ने। यज्ञं। नय। ऋतुऽथा। सं॒ऽइधानः। ऊं इति। संत्य।
शुक्रऽशोचे। इह। आ। वह। चिकित्वान्। दैव्यं। जनं। विप्रं। होतारं। अद्रुहं। धूमऽकेतुं। विभाऽवसुं। य
ज्ञानां। केतुं। ईमहे॥ ३ ॥ अग्ने। नि। पाहि। नः। त्वं। प्रति। स्म। देव। रिषतः। भिंधि। द्वेषः। सहःऽकृत।
अग्निः। प्रत्नेन। मन्मना। शुंभानः। तन्वं। स्वां। कविः। विप्रेण। ववृधे। ऊर्जः। नपातं। आ। हुवे। अ
ग्निं। पावकऽशोचिषं। अस्मिन्। यज्ञे। सुऽअध्वरे। सः। नः। मित्रऽमहः। त्वं। अग्ने। शुक्रेण। शोचि
षा॥ ० यः। अग्निं। तन्वः। दमे। देवं। मर्तः। सपर्यति। तस्मै। इत्। दीदयत्। वसु॥ ३५ ॥ अग्निः। मूर्द्धा।

© Dharmartha Trust J&K. Digitized by eGangotri

पष·

४१ दिवः।ककुत्।पतिः।पृथिव्याः।अयं।अपां।रेतांसि।जिन्वति।उत।अग्ने।शुचयः।तव।शुक्राः।भ्राजं
तः।ईरते।तव।ज्योतींषि।अर्चयः।ईशिषे।वार्यस्य।हि।दात्रस्य।अग्ने।स्वःऽपतिः।स्तोता।स्यां।तव
शर्मणि।त्वां।अग्ने।मनीषिणः।त्वां।हिन्वंति।चित्तिऽभिः।त्वां।वर्धंतु।नः।गिरः।अदब्धस्य।स्व
धाऽवतः।दूतस्य।रेभतः।सदा।अग्नेः।सख्यं।वृणीमहे।२०।अग्निः।शुचिव्रतऽतमः।शुचिः।
विप्रः।शुचिः।कविः।शुचिः।रोचते।आऽहुतः।उत।त्वा।धीतयः।मम।गिरः।वर्धंतु।विश्वहा।अ
ग्ने।सख्यस्य।बोधि।नः।यत्।अग्ने।स्यां।अहं।त्वं।त्वं।वा।घ।स्याः।अहं।स्युः।ते।सत्याः।इ
ह।आऽशिषः।वसुः।वसुऽपतिः।हि।कं।असि।अग्ने।विभाऽवसुः।स्याम।ते।सुऽमतौ।अपि।अ ४१

41

© Dharmartha Trust J&K. Digitized by eGangotri

ग्ने। घृतैः। अन्नाय। नः। समुद्रायऽइव। सिंधवः। गिरः। वाश्रासः। ईरते॥ ४०॥ युवानं। विश्पतिं। कविं। वि
श्वऽअदं। पुरुऽवेपसं। अग्निं। शुंभामि। मन्मऽभिः। यज्ञानां। रथ्ये। वयं। तिग्मऽजंभाय। वीळवे। स्तो
मैः। इषेम। अग्नये। अयं। अग्ने। त्वेइति। अपि। जरिता। भूतु। संत्य॥०॥ धीरः। हि। असि। अद्मऽस
त्। विप्रः। न। जागृविः। सदा। अग्ने। दीदयसि। द्यवि। पुरा। अग्ने। दुःऽइतेभ्यः। पुरा। मृध्रेभ्यः। कवे।
प्र। नः। आयुः। वसोइति। तिर॥ ४३॥ आ। घ। ये। अग्निं। इंधते। स्तृणंति। बर्हिः। आनुषक्। येषां। इंद्रः।
युवा। सखा। बृहन्। इत्। इध्मः। एषां। भूरि। शस्तं। पृथुः। स्वरुः॥०॥ अयुद्धः। इत्। युधा। वृतं। शूरः। आ।
अजति। सत्वऽभिः॥०॥ आ। बुंदं। वृत्रऽहा। ददे। जातः। पृच्छत्। वि। मातरं। कः। उग्राः। के। ह। शृण्विरे।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प॰ प्रति। त्वा। शवसी। वदत्। गिरौ। अप्सः। न। योधिषत्। यः। ते। शत्रुऽत्वं। आऽचके। ॥२॥ कृता। त्वां। मघ

४२ व वन्। शृणु। यः। ते। वष्टि। वंसि। ततता। यत्। वीळयासि। वीळु। ततता। यत्। आजिं। याति। आजिऽकृत्।

इंद्रः। स्वश्वऽयुः। उप। रथिऽतमः। रथिनां। वि। सु। विश्वाः। अभिऽयुजः। वज्रिन्। विष्वक्। यथा। वृ

ह। भव। नः। सुऽश्रवःऽतमः। अस्माकं। सु। रथं। पुरः। इंद्रः। कृणोतु। सातये। न। यं। धूर्वंति। धूर्तयः।

वृज्याम। ते। परि। द्विषः। अरं। ते। शक्र। दावने। गमेम। इत्। इंद्र। गोऽमतः। ॥३॥ शनैः। चित्। यंतः।

अद्रिऽवः। अश्वऽवंतः। शतऽग्विनः। विऽवक्षणाः। अनेहसः। ऊर्ध्वा। हि। ते। दिवेऽदिवे। सहस्रा। सू

नृता। शता। जरितृऽभ्यः। विऽमंहते। विद्म। हि। त्वा। धनंऽजयं। इंद्र। दृळ्हा। चित्। आऽरुजं। ५२

52

© Dharmartha Trust J&K. Digitized by eGangotri

आऽदारिणं।यथा।गयं।कुहा।चित्ता।त्वा।कुवा।मंदं।तु।धृष्णो इति।इंद्र।वः।आ।त्वा।पृणं।यत्।ईं।मह।
यः।ते।रेवान्।अदाशुरिः।प्रऽममर्ष।मघत्तये।तस्य।नः।वेदः।आ।भर॥१५॥इमे।ऊं इति।त्वा।वि।
चक्षते।सखायः।इंद्र।सोमिनः।पुष्टऽवंतः।यथा।पशुं॥उत।अवधिरं।वयं।श्रुत्ऽकर्णं।संतं।ऊ त्वा।
तये।दूरात्।इह।हवामहे॥यत्।शुश्रुयाः।इमं।हवं।दुःऽमर्षं।चक्रियाः।उत।भवेः।आपिः।नः।अं
तमः॥यत्।चित्।हि।ते।अपि।व्यथिः।जगन्वांसः।अमन्महि।गोऽदाः।इत्।इंद्र।बोधि।नः॥आ।
त्वा।रंभं।न।जिव्रयः।ररभ्म।शवसः।पते।उश्मसि।त्वा।सधऽस्थे।आ॥२०॥स्तोत्रं।इंद्राय।
गायत।पुरुऽनृम्णाय।सत्वने।नकिः।यं।वृण्वते।युधि॥अभि।त्वा।वृषभ।सुते।सुतं।सृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ आ।मि।पीतये।तं।पाहि।अभ्युद्धि।मदा।मा।आ।मूराः।अविष्यवः।मा।उपऽहस्वानः।आ।दभन्।

४३ माकीं।ब्रह्मऽद्विषः।वनः।इह।त्वा।गोऽपरीणसा।महे।मंदन्तु।राधसे।सरः।गौरः।यथा।पिब।या।

43 वृत्रऽहना।पराऽवति।सना।नवा।च।चुच्युवे।ता।संसत्ऽसु।प्र।वोचत॥४०॥अपिबत्।कद्रुवः।

सुतं।इन्द्रः।सहस्रऽबाह्वे।अत्र।अदेदिष्ट।पौंस्यं।सत्यं।तत्।तुर्वशे।यदौ।विदानः।अह्नवाय्यं।

वि।आनट्।तुर्वणे।शमि।तरणिऽवः।जनानां।त्रदं।वाजस्य।गोऽमतः।समानं।ऊं।इति।प्र।शं

सिष।ऋभुक्षणं।न।वर्तवे।उक्थेषु।तुग्र्यऽवृधं।०।यः।कृन्तत्।इत्।वि।योन्यं।त्रिऽशोकाय।

गिरिं।पृथुं।गोभ्यः।गातुं।निःऽएतवे॥४२॥यत्।दधिषे।मनस्यसि।मन्दानः।प्र।इत्।इयक्षसि ४३

© Dharmartha Trust J&K. Digitized by eGangotri

सोमा।न त्वा।कः।इंद्र।मृळया।दस्मे।चित्।हि।त्वाऽवतः।कृतं।शृण्वे।अधि।क्षमि।जिगातु।इंद्र।ते।मनः।
तव।इत्।ताः।सुऽकीर्तयः।असन्।उत।प्रऽशस्तयः।यत्।मा।नः।एकस्मिन्।आगसि।मा।द्वयोः
उत।त्रिषु।वधीः।मा।शूर।भूरिषु।बिभय।हि।त्वाऽवतः।उग्रात्।अभिऽप्रभंगिनः।दस्मात्।अ
हं।ऋतिऽसहः।४८।मा।सख्युः।शूनं।आ।विदे।मा।पुत्रस्य।प्रभुवसो इति प्रभुऽवसो।आऽवृ
त्वत्।भूतु।ते।मनः।कः।नु।मर्याः।अमिथितः।सखा।सखायं।अब्रवीत्।जहा।कः।अस्मत्।ईष
ते।एवारे।वृषभ।सुते।अस्मिन्व्ना।भूरि।आवयः।श्वघ्नीऽइव।निऽवता।चरन्।आ।ते।एता।वचः
ऽयुजा।हरी इति।गृभ्णे।सुमत्ऽरथा।यत्।ईं।ब्रह्मऽभ्यः।इत्।ददः।मिंधि।विश्वाः।अप।द्विषः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. परि।बाधः।जहि।मृधः।वसु।स्पार्हं।तत्।आ।भर।यत्।वीळौ।इंद्र।यत्।स्थिरे।यत्।पर्शाने।परा
४४ भृतं।यस्य।ते।विश्वः।मानुषः।भूरेः।दत्तस्य।वेदति।।४२।। इतिषष्ठाष्टके तृतीयोध्यायः।। ।।
ॐम।। त्वावतस्त्रयस्त्रिंशद्धशोऽभ्य आस आदिकानीतस्य पृथुश्रवसो दानस्तुतिराद्यापादनिचृत्पं
क्तिर्म्यादिककुब्गायत्र्यौ बृहत्यनुष्टुप्सतोबृहती गायत्री विपरीतोत्तरः प्रगाथो द्विपदा चतुर्विंशिका
बृहती पिपीलिकमध्या ककुम्न्यंकुशिरा विराट् जगत्युपरिष्टाद्बृहती बृहत्यो विषमपदा सतरा
पंक्तिः संस्तारपंक्तिर्गायत्री पंक्तिः प्रगाथौ च वायव्यौ गायत्री द्विपदा त्रिरूपंक्तिर्वा यव्या गाय
त्री महिषो वा त्रित आप्त्य आदित्येभ्यो त्याः पंचोपसेपि महापंक्तेः साद्यः पंचानां प्रगाथः से ४५

© Dharmartha Trust J&K. Digitized by eGangotri

ष्यं त्रैष्टुभं पंचमी जगत्यभि प्रदशा प्रस्कण्वः प्रगाथं त्वं प्र सुश्रुतं वृहि ग्रुर्यथा मनौ श्रुहि ग्रुर्यथा मना
वायुरुमं वा ष्टो मेध्य एतत्ते मातरिश्वा नौ विश्व इति वैश्वदेवः प्रगाथो मरुती पंच रुशः प्रस्कण्वस्य
दास्तुतिर्गायत्र्यंतु तृतीयांत्ये अनुष्टुभौ प्रतिलेष ष प्रौ त्याग्नि सौरी पंक्ति र्युवं देवा चतुष्कं मे ध्य
आश्विनं त्रैष्टुभं यमवि विजस्त्र च वैश्वदेवमा द्यर्विक स्तुति वैमानि वांस त्त तु पणे द्वय वरुणं आग
त्वमग्न आ विंशतिर्भर्गः प्रागाथं आग्नेयं प्रागाथं त्वं भयं ह्य नो ऽभो अस्मै द्वादश प्रगाथः पांक्तं सप्त
म्या धस्ति सौ रहस्यः स प्र्यो गायत्र्ममाद्य चतुर्थ्यो द्विदै सप्तमी चानुष्टुभौ त्या दैवी त्रिष्टुभु वायदि ह
तरेभिः पंचोनो कलिः प्रागाथः प्रागाथमं स्वानुष्टुप् त्यानु सैकामत्स्यः सांमदो मैत्राव हणि मौ

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. न्यो। वा। बहवो। वा। मस्या। आ। लेन। ह्वा। आदित्या। नस्तु। वंदेश। स्या। घा। स्ति। स्त्रो। प्यदितेः॥ ॥हरिः ॐ॥ म॥
४५ त्वाऽवतः। पुरूवसो इति पुरुऽवसो। वयं। इन्द्र। प्रणेतरिति प्रऽनेतः। स्मसि। स्थातः। हरीणां। त्वां। हि।
सत्यं। अद्रिऽवः। विद्म। दातारं। इषां। विद्म। दातारं। रयीणां। आ। यस्य। ते। महिमानं। शतं। ऊते। श
तक्रतो इति शतऽक्रतो। गीःऽभिः। गृणंति। कारवः। सुऽनीथः। घ। सः। मर्त्यः। यं। मरुतः। यं। अर्यमा।
मित्रः। पांति। अद्रुहः। दधानः। गोऽमत्। अश्वऽवत्। सुऽवीर्यं। आदित्यऽजूतः। एधते। सदा। राया।
पुरुऽस्पृहा॥ १॥ तं। इंद्रं। दानं। ईमहे। शवसानं। अभीर्वं। ईशानं। रायः। ईमहे। तस्मिन्। हि। संति।
ऊतयः। विश्वाः। अभीरवः। सचा। तं। आ। वहंतु। सप्तयः। पुरुऽवसुं। मदाय। हरयः। सुतं। यः। ते। म ४५

© Dharmartha Trust J&K. Digitized by eGangotri

दः । वरेण्यः । यः । इंद्र । वृत्रहन्ऽतमः । यः । आऽददिः । स्वः । नृऽभिः । यः । पृतनासु । दुस्तरः । यः । दुस्तरः । विश्व
ऽवारः । श्रवाय्यः । वाजेषु । अस्ति । तरुता । सः । नः । शविष्ठ । सवना । आ । वसो इति । गहि । गमेम । गोऽमति
व्रजे । गव्यो इति । सु । नः । यथा । पुरा । अश्वऽया । उत । रथऽया । वरिवस्य । महाऽमह ॥ २ ॥ नहि । ते । शूर । रा
धसः । अंतं । विंदामि । सत्रा । दशस्य । नः । मघऽवन् । नु । चित् । अद्रिऽवः । धियः । वाजेभिः । आविथ । यः । ऋ
ष्वः । श्रवयत्ऽसखा । विश्वा । इत् । सः । वेद । जनिम । पुरुऽस्तुतः । तं । विश्वे । मानुषा । युगा । इंद्रं । हवंते । तवि
षं । यतऽस्रुचः । सः । नः । वाजेषु । अविता । पुरुऽवसुः । पुरःऽस्थाता । मघऽवा । वृत्रऽहा । भुवत् । अभि । वः
वीरं । अंधसः । मदेषु । गाय । गिरा । महा । विऽचेतसं । इंद्रं । नाम । श्रुत्यं । शाकिनं । वचः । यथा । ददिः । रेक्णः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प॰ तन्वे । ददिः । वसु । ददिः । वाजेषु । पुरुऽहूत । वाजिनं । नूनं । अथ ॥ आ । विश्वेषां । इरज्यंतं । वसूनां । ससह्वांसं ।
४६ चित् । अस्य । वर्पसः । कृपयतः । नूनं । अति । अथ । महः । सु । वः । अरं । इषे । स्तवामहे । मीळ्हुषे । अरंऽग
माय । जग्मये । यज्ञेभिः । गीःऽभिः । विश्वऽमनुषां । मरुतां । इयक्षसि । गाये । त्वा । नमसा । गिरा ॥ ये । पात
यंते । अज्मऽभिः । गिरीणां । स्नुऽभिः । एषां । यज्ञं । महिऽस्वनीनां । सुम्नं । तुविऽस्वनीनां । प्र । अध्वरे । प्रऽ
भंगं । दुःऽमतीनां । इंद्र । शविष्ठ । आ । भर । रयिं । अस्मभ्यं । युज्यं । चोदयत्ऽमते । ज्येष्ठं । चोदयत्ऽमते । स
नितः । सुऽसनितः । उग्र । चित्र । चेतिष्ठ । सूनृत । प्रऽसहा । संऽराट् । सहुरिं । सहंतं । भुज्युं । वाजेषु ।
पूर्व्यं ॥ ४ ॥ आ । सः । एतु । यः । ईवत् । आ । अदेवः । पूर्तं । आऽददे । यथा । चित् । वशः । अश्व्यः । पृथुऽश्रवसि । ४६

© Dharmartha Trust J&K. Digitized by eGangotri

कानीते। अस्याः। सुऽउषि। आः। ददे। वशिं। सहस्रा। अश्व्यस्य। अयुता। असनं। उष्ट्रानां। विंशतिं। शता।
दश। श्यावीनां। शता। दश। त्रिऽअरुषीणां। दश। गवां। सहस्रा। दश। श्यावाः। ऋधत्ऽरयः। वीतऽवा-
रासः। आशवः। मथ्राः। नेमिं। नि। ववृतुः। दानासः। पृथुऽश्रवसः। कानीतस्य। सुऽराधसः। रथं। हि-
रण्ययं। ददत्। मंहिष्ठः। सूरिः। अभूत्। वर्षिष्ठं। अकृत। श्रवः। आ। नः। वायो इति। महे। तने। याहि। मखा-
य। पाजसे। वयं। हि। ते। चकृम। भूरि। दावने। सद्यः। चित्। महि। दावने॥ यः। [illegible] अश्वेभिः। वहते। वस्ते।
उस्राः। त्रिः। सप्त। सप्ततीनां। एभिः। सोमेभिः। सोमसुत्ऽभिः। सोमऽपाः। दानाय। शुक्रऽपूतऽपाः। यः।
मे। इमं। चित्। ऊं इति। त्मना। अमंदत्। चित्रं। दावने। अरट्वे। अक्षे। नहुषे। सुकृत्वनि। सुकृत्ऽतरा

© Dharmartha Trust J&K. Digitized by eGangotri

५.५. या। स्वुः। ऋतुं। उ। नृथ्यैः। वपुषि। यः। स्वःऽराट्। उत। वायो इति। घृतऽस्नाः। अश्वऽइषितं। रजःऽइषितं। शुनाऽ
८० इषितं। प्र। अज्म। तत्। इदं। नु। तत्। अध। प्रियं। इषिराय। षष्टिं। सहस्रा। असनं। अश्वानां। इत्। न। वृष्णां।
47 गावः। न। यूथं। उप। यंति। वध्रयः। उप। मा। आ। यंति। वध्रयः। अध। यत्। चारथे। गणे। शतं। उष्ट्रान्।
अचिक्रदत्। अध। श्वित्नेषु। विंशतिं। शता। शतं। दासे। बल्बूथे। विप्रः। तरुक्षे। आ। ददे। ते। ते। वायो
इति। इमे। जनाः। मदंति। इंद्रऽगोपाः। मदंति। देवऽगोपाः। अध। स्या। योषणा। मही। प्रतीची। वशं। अ
श्व्यं। अधिऽरुक्मा। वि। नीयते। ॥ महि। वः। महतां। अवः। वरुण। मित्र। दाशुषे। यं। आदित्याः। अ
भि। द्रुहः। रक्षथ। न। ईं। अघं। नशत्। अनेहसः। वः। ऊतयः। सुऽऊतयः। वः। ऊतयः। विद्। देवाः। अ ८०

© Dharmartha Trust J&K. Digitized by eGangotri

घानां।आदित्यासः।अपऽआऽकृतिं।पक्षा।वयः।यथा।उपरि।वि।अस्मे इति।शर्म।यच्छत।०वि।अस्मे इति।
अधि।शर्म।तत्।पक्षा।वयः।न।यंतन।विश्वानि।विश्वऽवेदसः।वरूथ्या।मनामहे।०यस्मै।अरा
सत।क्षयं।जीवातुं।च।प्रऽचेतसः।मनोः।विश्वस्य।घ।इत्।इमे।आदित्याः।रायः।ईशते।०परि।नः।
वृणजन्।अघा।दुःऽगानि।रथ्यः।यथा।०।आदित्यानां।उत।अवसि।०।७।परिऽह्वृता।इत्।अजनः। अना।
युष्माऽदत्तस्य।वायति।देवाः।अदभ्रं।आश।वः।यं।आदित्याः।अहेतन।०न।तं।तिग्मं।चन।त्यजः।
न।द्रासत्।अभि।तं।गुरु।यस्मै।ऊं इति।शर्म।सऽप्रथः।आदित्यासः।अराध्वं।०युष्मे इति।देवाः।
अपि।स्म।सि।युध्यंतःऽइव।वर्मऽसु।यूयं।महः।नः।एनसः।यूयं।अर्भात्।उरुष्यत।०अदितिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. नः।उरुष्यतु।अदितिः।शर्म।यच्छतु।माता।मित्रस्य।रेवतः।अर्यम्णः।वरुणस्य।च।०।यत्।देवाः।शर्म।श
५८ रणं।यत्।भद्रं।यत्।अनातुरं।त्रिऽधातु।यत्।वरूथ्यं।तत्।अस्मासु।वि।यंतन।०।।८।।आदित्याः।
58 अव।हि।ख्यत।अधि।कूलात्ऽइव।स्पशः।सुऽतीर्थं।अर्वतः।यथा।अनु।नः।नेषथ।सुऽगं।०।न।
इह।भद्रं।रक्षस्विने।न।अवऽयै।न।उपऽयै।उत।गवे।च।भद्रं।धेनवे।वीराय।च।श्रवस्यते।०।यत्
यत्। ।आविः।अपीच्यं।देवासः।अस्ति।दुःऽकृतं।त्रिते।तत्।विश्वं।आत्ये।आरे।अस्मत्।दधातन।०
यत्।च।गोषु।दुःऽस्वप्न्यं।यत्।च।अस्मे।इति।दुहितः।दिवः।त्रिताय।तत्।विभाऽवरि।आत्याय।
परा।वह।०।निष्कं।वा।घ।कृणवते।स्रजं।वा।दुहितः।दिवः।त्रिते।दुःऽस्वप्न्यं।सर्वं।आत्ये।परि। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

दद्मसि।०।।तत्ऽअन्नाय।तत्ऽअपसे।तं।भागं।उपऽसेदुषे।त्रिताय।च।द्विताय।च।उषः।दुःऽस्व
प्न्यं।वह।यथा।कलां।यथा।शफं।यथा।ऋणं।सं।नयामसि।एव।दुःऽस्वप्न्यं।सर्वं।आप्त्ये।सं।
नयामसि।०।अजैष्म।अद्य।असनाम।च।अभूम।अनागसः।वयं।उषः।यस्मात्।दुःऽस्वप्न्या
अभक्षि त्।अभैष्म।अप।तत्।उच्छतु।०।१०।स्वादोः।वयसः।सुऽमेधाः।सुऽआध्यः।वरिवोवित्ऽतरः।स्य। त
विश्वे।यं।देवाः।उत।मर्त्यासः।मधु।ब्रुवंतः।अभि।संऽचरंति।अंतरिति।च।प्रऽअगाः।अदितिः।भ अ
वासि।अवऽयाता।हरसः।दैव्यस्य।इंदो इति।इंद्रस्य।सख्यं।जुषाणः।श्रौष्टीऽइव।धुरं।अनु।
राये।ऋध्याः।अपाम।सोमं।अमृताः।अभूम।अगन्म।ज्योतिः।अविदाम।देवान्।[illegible]।

© Dharmartha Trust J&K. Digitized by eGangotri

५.१. किं। नूनं। अस्मान्। कृणवत्। अरातिः। किं। ऊं इति। धूर्तिः। अमृत। मर्त्यस्य। शं। नः। भव। हृदे। आ।
४९ पीतः। इंदो इति। पिताऽइव। सोम। सूनवे। सुशेवः। सखाऽइव। सख्ये। उरुशंस। धीरः। प्र। नः।
आयुः। जीवसे। सोम। तारीः। इमे। मा। पीताः। यशसः। उरुष्यवः। रथं। न। गावः। सं। अनाह। पर्वऽ
सु। ते। मा। रक्षंतु। विऽस्रसः। चरित्रात्। उत। मा। स्रामात्। यवयंतु। इंदवः॥ २॥ अग्निं। न। मा।
मथितं। सं। दिदीपः। प्र। चक्षय। कृणुहि। वस्यसः। नः। अथ। हि। ते। मदे। आ। सोम। मन्ये। रेवान्ऽ
इव। प्र। चर। पुष्टिं। अच्छ। इषिरेण। ते। मनसा। सुतस्य। भक्षीमहि। पित्र्यस्यऽइव। रायः। सोम।
राजन्। प्र। नः। आयूंषि। तारीः। अहानिऽइव। सूर्यः। वासराणि। सोम। राजन्। मृळय। नः। स्व ४९

© Dharmartha Trust J&K. Digitized by eGangotri

स्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि । अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनुऽकामं ।
परा । दाः । त्वं । हि । नः । तन्वः । सोम । गोपाः । गात्रेऽगात्रे । निऽससत्थ । नृऽचक्षाः । यत् । ते । वयं । प्रऽमि-
नाम । व्रतानि । सः । नः । मृळ । सुऽसखा । देव । वस्यः । ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् ।
हरिऽअश्व । पीतः । अयं । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रं । प्रऽतिरं । एमि । आयुः ।
॥१२॥ अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः । आ । सोमः ।
अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः । यः । नः । इन्दुः । पितरः । हृत्ऽसु । पी-
तः । अमर्त्यः । मर्त्यान् । आऽविवेश । तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ ।

© Dharmartha Trust J&K. Digitized by eGangotri

१.४. स्याम । त्वं । सोम । पितृऽभिः । संऽविदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ । तस्मै । ते । इन्दो इति ।
५० हविषा । विधेम । त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः । वयं ।
सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथं । आ । वदेम । त्वं । नः । सोम । विश्वतः । वयःऽधाः ।
त्वं । स्वःऽवित् । आ । विश । नृऽचक्षाः । त्वं । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उ
त । वा । पुरस्तात् ॥ ३३ ॥ बालखिल्यप्रारंभः ॥ अभि । प्र । वः । सुऽराधसं । इंद्रं । अर्च । यथा । विदे । यः
। जरितृऽभ्यः । मघऽवा । पुरुऽवसुः । सहस्रेणऽइव । शिक्षति । शतऽअनीकाऽइव । प्र । जिगाति । धृ
षुऽया । हंति । वृत्राणि । दाशुषे । गिरेःऽइव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुऽभोजसः । ५०

© Dharmartha Trust J&K. Digitized by eGangotri

आ। त्वा। सुताः। सः। इंदवः। मदाः। ये। इंद्र। गिर्वणः। आपः। न। वज्रिन्। अनु। ओक्यं। सरः। पृणंति। शू
र। राधसे। अनेहसं। प्रऽतरणं। विवक्षणं। मध्वः। स्वादिष्ठं। ईं। पिब। आ। यथा। मंदसानः। किरासि।
नः। प्र। क्षुद्राःऽइव। त्मना। धृषत्। आ। नः। स्तोमं। उप। द्रवत्। हियानः। अश्वः। न। सोतृऽभिः। यं। ते।
स्वधाऽवन्। स्वदयंति। धेनवः। इंद्र। कण्वेषु। रातयः॥ ३॥ उग्रं। न। वीरं। नमसा। उप। सेदिम। वि
ऽभूतिं। अक्षितऽवसुं। उद्रीऽइव। वज्रिन्। अवतः। न। सिंचते। क्षरंति। इंद्र। धीतयः। यत्। ह। नूनं।
यत्। वा। यज्ञे। यत्। वा। पृथिव्यां। अधि। अतः। नः। यज्ञं। आशुऽभिः। महेऽमते। उग्रः। उग्रेभिः। आ।
गहि। अजिरासः। हरयः। ये। ते। आशवः। वाताःऽइव। प्रऽसक्षिणः। येभिः। अपत्यं। मनुषः। परिऽ

© Dharmartha Trust J&K. Digitized by eGangotri

५.५. ईयसे। येभिः। विश्वं। स्वः। दृशे। तत्। आ। वहतः। न। ईं। महे। इंद्र। सुम्नस्य। गोऽमतः। यथा। प्र। अवः। मघऽव
५३ न्। मेध्यऽअतिथिं। यथा। नीपऽअतिथिं। धने। यथा। कण्वे। मघऽवन्। त्रसदस्यवि। यथा। पक्थे। द प
शऽव्रजे। यथा। गोऽशर्ये। असनोः। ऋजिश्वनि। इंद्र। गोऽमत्। हिरण्यऽवत्॥१०॥ प्र। सु। श्रुतं। सुऽ
राधसं। अर्च। शक्रं। अभिष्टये। यः। सुन्वते। स्तुवते। काम्यं। वसु। सहस्रेणऽइव। मंहते। शतऽअ
नीकाः। हेतयः। अस्य। दुस्तराः। इंद्रस्य। सं। इषः। महीः। गिरिः। न। भुज्मा। मघवत्ऽसु। पिन्वते।
यत्। ईं। सुताः। अमंदिषुः। यत्। ईं। सुतासः। इंदवः। अभि। प्रियं। अमंदिषुः। आपः। न। धायि। सव
नं। मे। आ। वसो इति। दुघाःऽइव। उप। दाशुषे। अनेहसं। वः। हवमानं। ऊतये। मध्वः। क्षरंति। धीत ५३

© Dharmartha Trust J&K. Digitized by eGangotri

यः। आ। त्वा। वसो इति। हवमानासः। इंदवः। उप। स्तोत्रेषु। दधिरे। आ। नः। सोमे। सु। अध्वरे। इयानः।
अत्यः। न। तोशते। यं। ते। स्वदावन्। स्वदंति। गूर्तयः। पौरे। छंदयसे। हवं॥ ३५॥ प्र। वीरं। उग्रं। वि
विचिं। धनऽस्पृतं। विऽभूतिं। राधसः। महः।०। वसुऽत्वना। सदा। पीपेथ। दाशुषे।०। पराऽवति।
यदिवि। आयुना। नः। इंद्र। हरिऽभिः। महेऽमते। ऋष्वः। ऋष्वेभिः। आ। गहि। रथिरासः।०। अस्त्रिधः।
ओजः। यातस्य। पिप्रति। येभिः। निऽदस्युं। मनुषः। निऽघोषयः। येभिः। स्वरु। रिति। स्वः। परिऽ
ईयसे।० तावतः। ते। वसो इति। विद्याम। शूर। नव्यसः।०। एतशः। रुव्यो। धने। यथा। वशं।
दरः। ब्रमे।०। मेधे। अध्वरे। दीर्घ। नीथा। दमे। नसि। यथा। गोऽशर्ये। असिसासः। अद्रिऽवः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ मयि। गोऽत्रं। हरिऽश्रियं॥१७॥ यथा। मनौ। सांऽवरणौ। सोमं। इंद्र। अपिबः। सुते। नीपऽअतिथौ।
५२ मेधऽअतिथौ। पुष्टिऽगौ। श्रुष्टिऽगौ। सचा। पार्षत्ऽवाणः। प्रस्कण्वं। सं। असादयत्।
५२ शयानं। जिव्रिं। उत्ऽहितं। सहस्राणि। असिसासत्। गवां। ऋषिः। त्वाऽऊतः। दस्यवे। वृकः।
यः। उक्थेभिः। न। विंधते। चिकित्। यः। ऋषिऽचोदनः। इंद्रं। तं। अछ। वद। नव्यस्या। मती। अरिष्यं
तं। न। भोजसे। यस्मै। अर्कं। सप्तऽशीर्षाणं। आनृचुः। त्रिऽधातुं। उत्ऽतमे। पदे। सः। तु। इमा।
विश्वा। भुवनानि। चिक्रदत्। आत्। इत्। जनिष्ट। पौंस्यं। यः। नः। दाता। वसूनां। इंद्रं। तं। हूमहे।
वयं। विद्म। हि। अस्य। सुऽमतिं। नवीयसीं। गमेम। गोऽमति। व्रजे॥१८॥ यस्मै। त्वं। वसो इति ५२

© Dharmartha Trust J&K. Digitized by eGangotri

नि। दाना। यः। स[illegible]परिशिक्षसि। सः। रायः। पोषं। अश्नुते। तं। त्वा। वयं। मघऽवन्। इंद्र। गि
र्वणः। सुतऽवंतः। हवामहे। कदा। चन। स्तरीः। असि। न। इंद्र। सश्चसि। दाशुषे। उपऽउप। इत्। नु।
मघऽवन्। भूयः। इत्। नु। ते। दानं। देवस्य। पृच्यते। प्र। यः। ननक्षे। अभि। ओजसा। क्रिविं। व
धैः। शुष्णं। निःऽघोषयन्। यदा। इत्। अस्तंभीत्। प्रथयन्। अमूं। दिवं। आ। इत्। जनिष्ट। पा
र्थिवः। यस्य। अयं। विश्वः। आर्यः। दासः। शेवधिऽपाः। अरिः। तिरः। चित्। अर्ये। रुशमे। पवी
रवि। तुभ्य। इत्। सः। अज्यते। रयिः। तुरण्यवः। मधुऽमंतं। घृतऽश्चुतं। विप्रासः। अर्कं। आनृ
चुः। अस्मे इति। रयिः। पप्रथे। वृष्ण्यं। शवः। अस्मे इति। सुवानासः। इंदवः॥ १०॥ यथा।

© Dharmartha Trust J&K. Digitized by eGangotri

प०ष० यथा। मनौ। विवस्वति। सोमं। शक्र। अपिबः। सुतं। यथा। त्रिते। छंदः। इंद्र। जुजोषसि। आयौ। माद
५३ यसे। सचा। पृषध्रे। मेध्ये। मातरिश्वनि। इंद्र। सुवाने। अमंदथाः। यथा। सोमं। दशऽशिप्रे। दशऽ
ओण्ये। स्यूमऽरश्मौ। ऋजूनसि। यः। उक्था। केवला। दधे। यः। सोमं। धृषिता। अपिबत्। यस्मै।
53 विष्णुः। त्रीणि। पदा। विऽचक्रमे। उप। मित्रस्य। धर्मऽभिः। यस्य। त्वं। इंद्र। स्तोमेषु। चाकनः। वाजे।
वाजिन्। शतक्रतो इति शतऽक्रतो। ०। सुदुघांऽइव। गोऽदुहः। जुहूमसि। श्रवस्यवः। ०। सः। नः। पि
ता। महान्। उग्रः। ईशानऽकृत्। अयामन्। उग्रः। मघऽवा। पुरुऽवसुः। गोः। अश्वस्य। प्र। दातु। नः
॥२०॥ ०। मंहसे। इन्वति। वसुऽयवः। वसुऽपतिं। शतऽक्रतुं। स्तोमैः। इंद्रं। हवामहे। कदा। चन। प्र। ५३

© Dharmartha Trust J&K. Digitized by eGangotri

युक्ष्वा । उमे इति । नि । पासि । जन्मनी इति । तुरीय । आदित्य । हवनं । ते । इंद्रियं । आ । तस्थौ । अमृतं ।
दिवि । यस्मै । त्वं । मघऽवन् । इंद्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे । अस्माकं । गिरः । उत । सुऽ
स्तुतिं । वसो इति । कण्वऽवत् । शृणुधि । हवं । अस्तावि । मन्म । पूर्व्यं । ब्रह्म । इंद्राय । वोचत । पूर्वीः । ऋ
तस्य । बृहतीः । अनूनुत । सं । क्षोणी इति । सं । ऊं इति । सूर्यं । सं । शुक्रासः । शुचयः । सं । गोऽआशिरः ।
सोमाः । इंद्रं । अमंदिषुः ॥ २३ ॥ उपऽमं । त्वा । मघोनां । ज्येष्ठं । च । वृषभाणां । पूर्भित्ऽतमं । मघऽवन् ।
इंद्र । गोऽविदं । ईशानं । रायः । ईमहे ॥ यः । आयुं । कुत्सं । अतिथिऽग्वं । अर्दयः । ववृधानः । दिवेऽदिवे ।
वं । हरिऽअश्वं । शतऽक्रतुं । वाजऽयंतः । हवामहे ॥ आ । नः । विश्वेषां । रसं । मध्वः । सिंचंतु । अद्रयः ।
अनृषता । स्तोतुः । मेधाः । अस्तृक्षाता । सः । इंद्रः । रायः । बृहतीः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. यो।पराऽवति।सुन्विरे।जनेषु।आ।यो।अर्वाऽवति।इंदवः।विश्वा।द्वेषांसि।जहि।च।अव।च।आ।कृ

५४ धि।विश्वे।सन्वंतु।आ।वसु।शीर्षेषु।चित्राः।ते।मदिरासः।अंशवः।यत्र।सोमस्य।तृंपसि॥२२॥इं

54 द्र।नेदीयः।आ।इत।इहि।मितऽमेधाभिः।ऊतिऽभिः।आ।शंऽतम।शंतमाभिः।अभिष्टिऽभिः।आ

सुऽआपे।स्वापिऽभिः।आजिऽतुरं।सत्ऽपतिं।विश्वऽचर्षणिं।कृधि।प्रऽजाः।सु।आऽभगं।प्र।स्तुति

राशीभिः।यो।ते।उक्थिनः।क्रतुं।पुनते।आनुषक्।यः।ते।साधिष्ठः।अवसे।ते।स्याम।भरेषु।ते।व

यं।होत्राभिः।उत।देवऽहूतिऽभिः।ससऽवांसः।मनामहे।अहं।हि।ते।हरिऽवः।ब्रह्म।वाजऽयुः।आ

जिं।यामि।सदा।ऊतिऽभिः।त्वां।इत।एव।ते।अमो।सं।अश्वऽयुः।गव्युः।अग्ने।मथीनां॥२३॥ ५४

© Dharmartha Trust J&K. Digitized by eGangotri

एतत्त्या।ते।इंद्र।वीर्यां।गीःऽभिः।गृणंति।कारवः।ते।स्तोभंतः।ऊर्जं।आवन्।घृतऽश्चुतं।पौरासः।नक्षन्।
धीतिऽभिः।नक्षंते।इंद्रं।अवसे।सुऽकृत्यया।येषां।सुतेषु।मंदसे।यथा।संऽवर्ते।अमदः।यथा।कृशे।
एव।अस्मे इति।इंद्र।मत्स्व।आ।नः।विश्वे।सऽजोषसः।देवासः।गंतन।उप।नः।वसवः।रुद्राः।अवसे।
नः।आ।गमन्।शृण्वंतु।मरुतः।हवं।पूषा।विष्णुः।हवनं।मे।सरस्वती।अवंतु।सप्त।सिंधवः।आपः।
।वातः।पर्वतासः।वनस्पतिः।शृणोतु।पृथिवी।हवं।यत्।इंद्र।राधः।अस्ति।ते।माघोनं।मघव
त्ऽतम।तेन।नः।बोधि।सधऽमाद्यः।वृधे।भगः।दानाय।वृत्रऽहन्।आजिऽपते।नृऽपते।त्वं।इत्।
हि।नः।वाजे।आ।वक्षि।सुक्रतो।इति सुऽक्रतो।वीती।होत्राभिः।उत।देववीतिऽभिः।ससऽवांसः।वि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.पं. ण्विरे। सं।लि। हि। अर्यै। आऽ।शिषः।इंद्रं। आयुः।जना। नो। अस्मान्। नक्ष स्वा। मघऽवन्। उपा। अवं। से।
५५ धुक्षस्व। विप्रुषी। इषम्। वयं। ते। इंद्र। स्तोमेभिः। विधेम। त्वं। अस्माकं। शतऽक्रतो। इति शतऽक्रतो।
महि। स्थूरं। शशयं। राधः। अह्रयं। प्रस्कण्वाय। नि। तोशय। २५। भूरि। इत्। इंद्रस्य। वीर्यं। वि।
अख्यं। अभि। आ। अयति। राधः। ते। दस्यवे। वृक। शतं। श्वेतासः। उक्षणः। दिवि। तारः। न। रोचंते।
महा। दिवं। न। तस्तंभुः। शतं। वेणून्। शतं। शुनः। शतं। चर्मणि। म्लाता नि। शतं। मे। बल्बुजऽस्तु
काः। अरुषीणां। चतुःऽशतं। सुऽदेवाः। स्थ। काण्वऽयनाः। वयःऽवयः। विऽचरंतः। अश्वासः। न।
चंक्रमत। आ। त्वा। इत्था। सात्तस्य। चाकिरन्। ना। अनूनस्य। महि। श्रवः। श्यावीः। अति। ध्वसन्। पथा। ५५

© Dharmartha Trust J&K. Digitized by eGangotri

चक्षुषा । चन । सं॒ऽनशे ॥ २६ ॥ प्रति । ते । दस्यवे । वृक । राधः । अदर्शि । अह्रयं । द्यौः । न । प्रथिना । शवः । द

श । मह्यं । पौतऽक्रतः । सहस्रा । दस्यवे । वृकः । नित्यात् । रायः । अमंहत । शतं । मे । गर्दभानां । शतं । ऊ

र्णाऽवतीनां । शतं । दासान् । अति । स्रजः । तत्रो इति । अपि । प्र । अनीयत । पूतऽक्रतायै । विऽअक्ता ।

अश्वानां । इत् । न । यूथ्यां । अचेति । अग्निः । चिकितुः । हव्यऽवाट् । सः । सुमत्ऽरथः । अग्निः । शुक्रे

ण । शोचिषा । बृहत् । सूरः । अरोचत । दिवि । सूर्यः । अरोचत ॥ २७ ॥ युवं । देवा । क्रतुना । पूर्व्येण । यु

क्ता । रथेन । तविषं । यजत्रा । आ । अगच्छतं । नासत्या । शचीभिः । इदं । तृतीयं । सवनं । पिबाथः । यु

वां । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् । अस्माकं । यज्ञं । सवनं । जुषा

© Dharmartha Trust J&K. Digitized by eGangotri

प.१. णा।पातं।सोमं।अश्विना।दीद्यग्नी इति दीदिऽअग्नी।पनाय्यं।तत्।अश्विना।कृतं।वां।वृषभः।
५६ दिवः।रजसः।पृथिव्याः।सहस्रं।शंसाः।उत।ये।गोऽइष्टौ।सर्वान्।इत्।तान्।उप।याता।पिब
ध्यै।अयं।वां।भागः।निऽहितः।यजत्रा।इमाः।गिरः।नासत्या।उप।याता।पिबतं।सोमं।मधुऽमं
तं।अस्मे इति।प्रऽदाश्वांसा।अवतं।शचीभिः।रत्वा।यं।ऋत्विजः।बहुऽधा।कल्पयन्तः।सऽचेत
सः।यज्ञं।इमं।वहंति।यः।अनूचानः।ब्राह्मणः।युक्तः।आसीत्।का।स्वित्।तत्र।यजमान
स्य।संऽवित्।एकः।एव।अग्निः।बहुऽधा।संऽइद्धः।एकः।सूर्यः।विश्वं।अनु।प्रऽभूतः।एका।
एव।उषाः।सर्वं।इदं।वि।भाति।एकं।वै।इदं।वि।बभूव।सर्वं।ज्योतिष्मंतं।केतुऽमंतं।त्रिऽच ५६

56

© Dharmartha Trust J&K. Digitized by eGangotri

कः। सुऽस्वं। रथं। सुऽसदं। भूरिऽवारं। चित्रऽमघाय स्यां। योगे। अधिऽजज्ञे। तं। वां। कृवे। अति। रिक्तं। पि
बध्यै।। रत्नाऽइमानि। वां। भागऽधेयानि। सिस्रतु। इंद्रावरुणा। प्र। मह। सुतेषु। वां। यज्ञेऽयज्ञे। हा। स
वना। भुरण्यथः। यत्। सुन्वते। यजमानाय। शिक्षथः।। निःऽसिध्वरीः। ओषधीः। आपः। आस्तां।
इंद्रावरुणा। महिमानं। आशत।या।। सिस्रतुः। रजसः। पारे। अध्वनः। ययोः। शत्रुः। नकिः। अदेवः। ओ
हते।। सत्यं। तत्। इंद्रावरुणा। कृशस्य। वां। मध्वः। ऊर्मिं। दुहते। सप्त। वाणीः। ताभिः। दाश्वांसं। अव
तं। शुभः। पती इति। यः। वां। अदब्धः। अभि। पाति। चित्तिऽभिः। घृतऽप्रुषः। सौम्याः। जीरऽदानवः।
सप्त। स्वसारः। सदने। ऋतस्य। याः। ह। वां। इंद्रावरुणा। घृतऽश्चुतः। ताभिः। धत्तं। यजमाना

© Dharmartha Trust J&K. Digitized by eGangotri

१.५. या।शिक्षतं।।ऋणा।अवोचाम।महत्वे।सोमगाय।सत्यं।त्वेषाभ्यां।महिमानं।इंद्रियं।अस्मान्।सु।
५८ इंद्रावरुणा।घृतऽश्चुतः।त्रिऽभिः।साप्तेभिः।अवतं।शुभः।पती इति।इंद्रावरुणा।यता।ऋषिऽभ्यः।
मनीषां।वाचः।मतिं।श्रुतं।अदत्तं।अग्रे।यानि।स्थानानि।असृजंत।धीराः।यज्ञं।तन्वानाः।त
पसा।अभि।अपश्यं।इंद्रावरुणा।सौमनसं।अदृप्तं।रायः।पोषं।यजमानेषु।धत्तं।प्रऽजां।पुष्टिं।
भूतिं।अस्मासु।धत्तं।दीर्घायुऽत्वाय।प्र।तिरतं।नः।आयुः॥३॥अनुवाकः॥ ॥अग्ने।आ।या
हि।अग्निऽभिः।होतारं।त्वा।वृणीमहे।आ।त्वां।अनक्तु।प्रऽयता।हविष्मती।यजिष्ठं।बर्हिः।आ
ऽसदे।अच्छ।हि।त्वा।सहसः।सूनो इति।अंगिरः।स्रुचः।चरंति।अध्वरे।ऊर्जः।नपातं।घृतऽकेशं। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

ईमहे । अग्निं । यज्ञेषु । पूर्व्यं । अग्ने । कविः । वेधाः । असि । होता । पावकः । यक्ष्यः । मंद्रः । यजिष्ठः । अध्वरेषु ।
ईड्यः । विप्रेभिः । शुक्र । मन्मऽभिः । अद्रोघं । आ । वह । उशतः । यविष्ठ । देवान् । अजस्र । वीतये । अभि ।
प्रयांसि । सुऽधिता । आ । वसोऽइति । गहि । मंदस्व । धीतिऽभिः । हितः । त्वं । इत् । सऽप्रथाः । असि । अग्ने ।
त्रातः । ऋतः । कविः । त्वां । विप्रासः । संऽइधान । दीदिऽवः । आ । विवासंति । वेधसः ॥ ३२ ॥ शोच । शोचि-
ष्ठ । दीदिहि । विशे । मयः । रास्व । स्तोत्रे । महान् । असि । देवानां । शर्मन् । मम । संतु । सूरयः । शत्रुऽ-
सहः । सुऽअग्नयः । यथा । चित् । वृद्धं । अतसं । अग्ने । संऽजूर्वसि । क्षमि । एव । दह । मित्रऽमहः ।
यः । अस्मऽध्रुक् । दुःऽमन्मा । कः । च । वेनति । मा । नः । मर्ताय । रिपवे । रक्षस्विने । मा । अघऽशंसा

प.ष. या।रीरधः।असेधत्ऽभिः।तरणिऽभिः।यविष्ठ्य।शिवेभिः।पाहि।पायुऽभिः।पाहि।नः।अग्ने।ए

६८ कया।पाहि।उत।द्वितीयया।पाहि।गीःऽभिः।तिसृऽभिः।ऊर्जां।पते।पाहि।चतसृऽभिः।वसो इ

ति।पाहि।विश्वस्मात्।रक्षसः।अराव्णः।प्र।स्म।वाजेषु।नः।अव।त्वां।इत्।हि।नेदिष्ठं।देवऽतात

58 ये।आपिं।नक्षामहे।वृधे।।३३।।आ।नः।अग्ने।वयःऽवृधं।रयिं।पावक।शंस्यं।रास्व।च।नः।उ

पऽमाते।पुरुऽस्पृहं।सुऽनीती।स्वयशःऽतरं।येन।वंसाम।पृतनासु।शर्धतः।तरंतः।अर्यः।आऽ

दिशः।सः।त्वं।नः।वर्ध।प्रयसा।शचीवसो इति शचीऽवसो।जिन्व।धियः।वसुऽविदः।शिशानः।

ना। वृषभः।यथा।अग्निः।शृंगे इति।दविध्वत्।तिग्माः।अस्य।हनवः।प्रतिऽधृषे।सुऽजंभः।सहसः। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

यहुः। नहि। ते। अग्ने। वृषभ। प्रतिऽधृषे। जंभासः। यत्। विऽतिष्ठसे। ०। होतरिति। सुऽहुतं। हविः। कृ
धि। वंस्व। नः। वार्या। पुरु। शेषे। वनेषु। मात्रोः। सं। त्वा। मर्त्तासः। इंधते। अतंद्रः। हव्या। वहसि। ह
विःऽकृतः। आत्। इत्। देवेषु। राजसि। ३५। सप्त। होतारः। तं। इत्। ईळते। त्वा। अग्ने। सुऽत्यजं। अ
ह्रयं। भिनत्सि। अद्रिं। तपसा। वि। शोचिषा। प्र। अग्ने। तिष्ठ। जनान्। अति। अग्निंऽअग्निं। वः। अध्रि
ऽगुं। हुवेम। वृक्तऽबर्हिषः। अग्निं। हितऽप्रयसः। शश्वतीषु। आ। होतारं। चर्षणीनां। केतेन। शर्म
न्। सचते। सुऽसामनि। अग्ने। तुभ्यं। चिकित्वना। इषण्यया। नः। पुरुऽरूपं। आ। भर। वाजं। ने
दिष्ठं। ऊतये। अग्ने। जरितः। विश्पतिः। तेपानः। देव। रक्षसः। अप्रोषिऽवान्। गृहऽपतिः। महान्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ अस्ति। दिवः। पायुः। दुरोणऽयुः। मा। नः। रक्षः। आ। वेशीत्। आघृणिवसो इत्याघृणिऽवसो। मा। या
५९ तुः। यातुऽमावतां। परः। गव्यूतिं। अनिरां। अप। क्षुधं। अग्ने। सेध। रक्षस्विनः। ३५। उभयं। श्रृणव
त्। च। नः। इंद्रः। अर्वाक्। इदं। वचः। सत्राच्या। मघऽवा। सोमऽपीतये। धिया। शविष्ठः। आ। गमत्। तं। हि।
59 स्वऽराजं। वृषभं। तं। ओजसे। धिषणे इति। निःऽततक्षतुः। उत। उपऽमानां। प्रथमः। नि। सीदसि। सोमऽ
कामं। हि। ते। मनः। आ। वृषस्व। पुरुऽवसो इति पुरुऽवसो। सुतस्य। इंद्र। अंधसः। विद्म। हि। त्वा। हरिऽवः।
पृत्ऽसु। ससहिं। अधृष्टं। चित्। दधृषणिं। अप्रामिऽसत्य। मघऽवन्। तथा। इत्। असत्। इंद्र। क्र
त्वा। यथा। वशः। सनेम। वाजं। तव। शिप्रिन्। अवसा। मक्षु। चित्। यंतः। अद्रिऽवः। शग्धि। ऊं इति। ५९

© Dharmartha Trust J&K. Digitized by eGangotri

सु।शचीऽपते।इंद्र।विश्वाभिः।ऊतिऽभिः।भगं।न।हि।त्वा।यशसं।वसुऽविदं।अनु।शूर।चरामसि।इद्धा।
पौरः।अश्वस्य।पुरुऽकृत्।गवां।असि।उत्सः।देव।हिरण्ययः।नकिः।हि।दानं।परिऽमर्धिषत्।त्वेइति।
यत्ऽयत्।यामि।तत्।आ।भर।त्वं।हि।आ।इहि।चेरवे।विदाः।भगं।वसुत्तये।उत्।वावृषस्व।मघऽव
न्।गोऽइष्टये।उत्।इंद्र।अश्वऽइष्टये।त्वं।पुरू।सहस्राणि।शतानि।च।यूथा।दाना।य।मंहसे।आ।पुरंऽ ता
दरं।चकृम।विप्रऽवचसः।इंद्रं।गायंतः।अवसे।अविप्रः।वा।यत्।अविधत्।विप्रः।वा।इंद्र।ते।व
चः।सः।प्र।ममंदत्।त्वाऽया।शतक्रतोइति शतऽक्रतो।प्राचामन्योइति प्राचाऽमन्यो।अहंऽसन।उ
ग्रऽबाहुः।मृक्षः।कृत्वा।पुरंऽदरः।यदि।मे।शृणवत्।हवं।वसुऽयवः।वसुऽपतिं।शतऽक्रतुं।स्तोमैः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ इंद्रं। हवामहे। ३॥ न। पापासः। मनामहे। न। अरायासः। न। जल्हवः। यत्। इत्। नु। इंद्रं। वृषणं। सचा। सुते।
६० सखायं। कृणवामहै। उग्रं। युयुज्म। पृतनासु। सासहिं। ऋणऽकातिं। अदाभ्यं। वेद। भृमं। चित्। सनिता।
रथिऽतमः। वाजिनं। यं। इत्। ऊं इति। नशत्। यतः। इंद्र। भयामहे। ततः। नः। अभयं। कृधि। मघऽवन्। शा
ग्धि। तव। तत्। नः। ऊतिऽभिः। वि। द्विषः। वि। मृधः। जहि। त्वं। हि। राधः। पते। राधसः। महः। क्षयस्य। अ
सि। विधतः। तं। त्वा। वयं। मघऽवन्। इंद्र। गिर्वणः। सुतऽवंतः। हवामहे। इंद्रः। स्पट्। उत। वृत्रऽहा। परःऽ
पाः। नः। वरेण्यः। सः। नः। रक्षिषत्। चरमं। सः। मध्यमं। सः। पश्चात्। पातु। नः। पुरः। त्वं। नः। पश्चा
त्। अधरात्। उत्तरात्। पुरः। इंद्र। नि। पाहि। विश्वतः। आरे। अस्मत्। कृणुहि। दैव्यं। भयं। आरे। हेतीः। ६०

60

© Dharmartha Trust J&K. Digitized by eGangotri

अदेवीः। अयथः। अशयः। श्वसःऽश्वसः। इंद्र। ज्ञास्त्वा। परे। चा। नः। विश्वा। चा। नः। जरितृ। नरा। सत्ऽपते। अहा। दिवा।
नक्तं। चा। रक्षिषः। प्रऽभंगी। शूरः। मघऽवा। तुविऽमघः। संऽमिश्लः। वीर्याय। कं। उभा। ते। बाहू इति। वृष
णा। शतक्रतो इति शतऽक्रतो। नि। या। वज्रं। मिमिक्षतुः। ३९। प्रो इति। अस्मै। उपऽस्तुतिं। भरत। यत्।
जुजोषति। उक्थैः। इंद्रस्य। माहिनं। वयः। वर्द्धंति। सोमिनः। भद्राः। इंद्रस्य। रातयः। अयुजः। असमः। नृऽ न
भिः। एकः। कृष्टीः। अयास्यः। पूर्वीः। अति। प्र। ववृधे। विश्वा। जातानि। ओजसा। ०। अहितेन। चित्।
अर्वता। जीरऽदानुः। सिसासति। प्रऽवाच्यं। इंद्र। तत्। तव। वीर्याणि। करिष्यतः। ०। आ। याहि। कृणवा
म। ते। इंद्र। ब्रह्माणि। वर्द्धना। येभिः। शविष्ठ। चाकनः। भद्रं। इह। श्रवस्यते। ०। धृषतः। चित्। धृषत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. मनः। कृणोषि। इंद्राय। त्वा। तीव्रैः। सोमैः। सपर्यतः। नमःऽभिः। प्रतिऽभूषतः।। अवा। चुश्चो। ऋचीष
६१ मः। अवतान्ऽइव। मानुषः। जुष्ट्वी। दक्षस्य। सोमिनः। सखायं। कृणुते। युजं।।४।। विश्वे। ते। इंद्र। वीर्यं।
देवाः। अनु। क्रतुं। ददुः। भुवः।। विश्वस्य। गोऽपतिः। पुरुऽस्तुत।। गृणे। तत्। इंद्र। ते। शवः। उपऽमं। देवऽतात
61
ये। यत्। हंसि। वृत्रं। ओजसा। शचीऽपते।। समना ऽइव। वपुष्यतः। कृणवत्। मानुषा। युगा। विदे। तत्।
इंद्रः। चेतनं। अध। श्रुतः।। उत्। जातं। इंद्र। ते। शवः। उत्। त्वां। उत्। तव। क्रतुं। भूरिगो इति भूरिऽगो। भूरि।
ववृधुः। मघऽवन्। तव। शर्मणि।। अहं। च। त्वं। च। वृत्रऽहन्। सं। युज्याव। सनिऽभ्यः। आ। अरातिऽवा।
चित्। नु। अद्रिऽवः। अनु। नौ। शूर। मंसते।। सत्यं। इत्। वै। ऊं इति। तं। वयं। इंद्रं। स्तवाम। न। अनृतं। म ६२

हान्।असुन्वतः।वधः।भूरि।ज्योतींषि।सुन्वतः।।४।।सः।पूर्व्यः।महानाम्।वेनः।क्रतुऽभिः।आनजे।यस्य।
द्वारा।मनुः।पिता।देवेषु।धियः।आनजे।दिवः।मानं।न।उत्।सदन्।सोमऽपृष्ठासः।अद्रयः।उक्था।ब्रह्म।
च।शंस्या।सः।विद्वान्।अंगिरःऽभ्यः।इंद्रः।गाः।अवृणोत्।अप।स्तुषे।तत्।अस्य।पौंस्यं।सः।प्रत्नऽथा।क
विऽवृधः।इंद्रः।वाकस्य।वक्षणिः।शिवः।अर्कस्य।होमनि।अस्मऽत्रा।गंतु।अवसे।आ।तु।ऊं इति।नु।ते।अ
नु।क्रतुं।स्वाहा।वरस्य।यज्यवः।श्वात्रं।अर्काः।अनूषत।इंद्र।गोत्रस्य।दावने।इंद्रे।विश्वानि।वीर्या।
कृतानि।कर्त्वानि।च।यं।अर्काः।अध्वरं।विदुः।।५।।यत्।पांचऽजन्यया।विशा।इंद्रे।घोषाः।असृक्ष
त।अस्तृणात्।बर्हणा।विपः।अर्यः।मानस्य।सः।क्षयः।इयं।ऊं इति।ते।अनुऽस्तुतिः।चकृषे।तानि।पौं

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. स्या।म्।आवृः।कः।ईं।चेत्सदा।वर्त्तनिं।अस्या।वृष्ट्वः।वि।ओदने।उत्।हा।कः।मित्रा।जीवसे।यवं।न।पश्वः।आ।ददे।त

६२ त्।दधानाः।अवस्यवः।युष्माभिः।दक्षऽपितरः।स्याम।मरुत्वतः।वृधे।बदे।कवित्रियाः।या।धाम्नि।कः।कुः

भिः।भरत।नो।नु।मः।जेषाम।इंद्र।त्वया।युजा।अस्मे इति।रुद्राः।मेहना।पर्वतासः।वृत्रऽहत्ये।भरऽहूतौ।

सऽजोषाः।।धायि।पज्रः।इंद्रऽज्येष्ठाः।अस्मान्।अवंतु।देवाः।।५।३।उत्।ता।ता।मंदं।लु।स्तोमाः।कृणु।घार

धेः।अद्रिऽवः।अव।ब्रह्म।द्विषः।जहि।पदा।पणीन्।अराधसः।नि।बाधस्व।महान्।असि।नहि।त्वा।कः।

चन।प्रति।त्वं।ईशिषे।सुतानां।इंद्र।त्वं।असुतानां।त्वं।राजा।जनानां।आ।इहि।प्र।इहि।क्षयः।आ।घो

षन्।चर्षणीनां।आ।उभे इति।पृणासि।रोदसी इति।त्वं।चित्।पर्वतं।गिरिं।शतऽवंतं।सहस्रिणं। ६२

दिवि।

© Dharmartha Trust J&K. Digitized by eGangotri

विऽस्तोऽत्रऽस्म्यंः। रुरोजिथ। वयं। कुं इति। त्वा। दिवा। सुते। वयं। नक्तं। हवामहे। अस्माकं। कामं। आ। पृण॥४७॥

कं। स्यः। वृषभः। युवा। तुविऽग्रीवः। अनानतः। ब्रह्मा। कः। तं। सपर्यति। कस्य। स्वित्। सवनं। वृषा। जुजु

षाणः। अव। गच्छति। इंद्रं। कः। कुं इति। स्वित्। आ। चके। कं। ते। दानाः। असक्षत। वृत्रऽहन्। कं। सुऽवीर्या। उ

क्थे। कः। कुं इति। स्वित्। अंतमः। अयं। ते। मानुषे। जने। सोमः। पूरुषु। सूयते। तस्य। आ। इहि। प्र। द्रव।

पिब। अयं। ते। शर्यणाऽवति। सुऽसोमायां। अधि। प्रियः। आर्जीकीये। मदिन्ऽतमः। तं। अद्य। राधसे।

महे। चारुं। मदाय। घृष्वये। आ। इहि। ईं। इंद्र। द्रव। पिब॥४८॥ आ। याहि। तूयं। आशुऽभिः। यत्। वा।

प्रऽस्रवणे। दिवः। मादयासे। स्वःऽनरे। यत्। वा। समुद्रे। अंधसः। आ। त्वा। गीःऽभिः। महां। उरुं।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. हुवे। गोःऽइव। भोजसे। इंद्र। सोमस्य। पीतये। आ। नः। इंद्र। महिमानं। हरयः। देव। ते। महः। रथे। वहंतु। बिभ्रतः।
६३ इंद्र। गृणीषे। ऊं इति। स्तुषे। महान्। उग्रः। ईशानऽकृत्। आ। इहि। नः। सुतं। पिब। सुतऽवंतः। त्वा। वयं। प्रय
स्वंतः। हवामहे॥४॥ इंद्र। ते। सोम्यं। मधु। अधुक्षन्। अद्रिऽभिः। नरः। जुषाणः। इंद्र। तत्। पिब।
विश्वान्। अर्यः। विपःऽचितः। अति। ख्यः। तूयं। आ। गहि। दाता। मे। पृषतीनां। राजा। हिरण्यऽवी
नां। मा। देवाः। मघऽवा। रिषत्। सहस्रे। पृषतीनां। अधि। चंद्रं। बृहत्। पृथु। शुक्रं। हिरण्यं। आ। ददे।
नपातः। दुःऽगहस्य। मे। सहस्रेण। सुऽराधसः। श्रवः। देवेषु। अक्रत॥४७॥ तरःऽभिः। वः। विदत्ऽ
वसुं। इंद्रं। सऽबाधः। ऊतये। बृहत्। गायंतः। सुतऽसोमे। अध्वरे। हुवे। भरं। न। कारिणं। न। यं। दुध्राः। ६३

© Dharmartha Trust J&K. Digitized by eGangotri

वरंते। न। स्थिराः। मुरः। मदे। सुऽशिप्रं। अंधसः। यः। आऽदृत्य। शशमानाय। सुन्वते। दाता। जरित्रे। उक्थ्यं॥ यः।
शक्रः। मृक्षः। अश्व्यः। यः। वा। कीजः। हिरण्ययः। सः। ऊर्वस्य। रेजति। अपऽवृतिं। इंद्रः। गव्यस्य। वृत्रऽहा।
चित्। निऽखातं। यः। पुरुऽसंभृतं। वसु। उत्। इत्। वपति। दाशुषे। वज्री। सुऽशिप्रः। हरिऽअश्वः। इत्। करत्। इंद्रः।
क्रत्वा। यथा। वशत्॥ यत्। वा। ववंथ। पुरुऽस्तुत। पुरा। चित्। शूर। नृणां। वयं। तत्। ते। इंद्र। सं। भरामसि।
यज्ञं। उक्थं। तुरं। वचः॥ ४८॥ सचा। सोमेषु। पुरुऽहूत। वज्रिऽवः। मदाय। द्युक्ष। सोमऽपाः। त्वं। इत्। हि। ब्रह्मऽ
कृते। काम्यं। वसु। देष्ठः। सुन्वते। भुवः॥ वयं। एनं। इदा। ह्यः। अपीपेम। इह। वज्रिणं। तस्मै। ऊं इति।
अद्य। समना। सुतं। भर। आ। नूनं। भूषत। श्रुते। वृकः। चित्। अस्य। वारणः। उरामथिः। आ। वयुनेषु। भूषत

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. ति। सः। इमं। नः। स्तोमं। जुजुषाणः। आ। गहि। इंद्र। प्र। चित्रया। धिया। कत्। ऊं इति। नु। अस्य। अकृतं। इं

६४ द्रस्य। अस्ति। पौंस्यं। केनो इति। नु। कं। श्रोमतेन। न। शुश्रुवे। जनुषः। परि। वृत्रऽहा। कत्। ऊं इति। महीः। ना

64 अधृष्टाः। अस्य। तविषीः। कत्। ऊं इति। वृत्रऽघ्नः। अस्तृतं। इंद्रः। विश्वान्। वेकऽनाटान्। अहःऽदृशः।

उत। क्रत्वा। पणीन्। अभि॥ ८॥ वयं। घ। ते। अपूर्व्या। इंद्र। ब्रह्माणि। वृत्रऽहन्। पुरुऽतमासः। पुरुऽहूत।

ग्रा वज्रिऽवः। भर्तिं। न। प्र। भरामसि। पूर्वीः। चित्। हि। त्वे इति। तुविऽकूर्मिन्। आऽशसः। हवंते। इंद्र। ऊतयः।

तिरः। चित्। अर्यः। सवना। [illegible]। आ। वसो इति। गहि। शविष्ठ। श्रुधि। मे। हवं। त्वे इति। इत्था। ऊं इति।

इंद्र। विप्राः। अपि। स्मसि। नहि। त्वत्। अन्यः। पुरुऽहूत। कः। चन। मघऽवन्। अस्ति। मर्डिता। त्वं। नः। ६४

© Dharmartha Trust J&K. Digitized by eGangotri

अस्याः। अमतेः। उत। क्षुधः। अभिऽशस्तेः। अव। स्पृधि। त्वं। नः। ऊती। तव। चित्रया। धिया। शिक्ष। शचिष्ठ। गातुऽ
वित्। सोमः। इन्द्र। वः। सुतः। अस्तु। कलयः। मा। बिभीतन। अप। इत्। एषः। ध्वस्मा। अयति। स्वयं। घ। एषः।
अप। अयति॥५०॥ त्यान्। नु। क्षत्रियान्। अवः। आदित्यान्। याचिषामहे। सुऽमृळीकान्। अभिष्टये। मि
त्रः। नः। अति। अंहतिं। वरुणः। पर्षत्। अर्यमा। आदित्यासः। यथा। विदुः। तेषां। हि। चित्रं। उक्थ्यं। वरू
थं। अस्ति। दाशुषे। आदित्यानां। अरंऽकृते।०। जीवान्। नः। अभि। धेतन। आदित्यासः। पुरा। हथात्।
कत्। ह। स्थ। हवनऽश्रुतः॥५३॥ यत्। वः। श्रान्ताय। सुन्वते। वरूथं। अस्ति। यत्। छर्दिः। तेन। नः। अधि।
वोचत। अस्ति। देवाः। अंहोः। उरु। अस्ति। रत्नं। अनागसः। आदित्याः। अद्भुतऽएनसः। मा। नः। सेतुम

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.प. सिसेत् । अयं । महे । वृणक्तु । नः । [परि ।] इन्द्रः । इत्था । हि । श्रुतः । वशी । मा । नः । मृचा । रिपूणां । वृजिनानां । अविष्यवः ।
६५ देवाः । अभि । प्र । मृक्षत । उत । त्वां । अदिते । महि । अहं । देवि । उप । ब्रुवे । सुऽमृळीकां । अभिष्टये ॥ ५२ ॥
पर्षि । दीने । गभीरे । आ । उग्रऽपुत्रे । जिघांसतः । माकिः । तोकस्य । नः । रिषत् । अनेहः । नः । उरुऽव्र
ज्रे । उरूचि । वि । प्रऽसर्तवे । कृधि । तोकाय । जीवसे । ये । मूर्धानः । क्षितीनां । अदब्धासः । स्वऽयशसः । व्र
ता । रक्षन्ते । अद्रुहः । ते । नः । आस्नः । वृकाणां । आदित्यासः । मुमोचत । स्तेनं । बद्धं । इव । अदिते ।
अपो इति । सु । नः । इयं । शरुः । आदित्याः । अप । दुःऽमतिः । अस्मत् । एतु । अजघ्नुषी ॥ ५३ ॥ शश्वत् । हि ।
वः । सुऽदानवः । आदित्याः । ऊतिऽभिः । वयं । पुरा । नूनं । बुभुज्महे । शश्वन्तं । हि । प्रऽचेतसः । प्रतिऽयन्तं । ६५

© Dharmartha Trust J&K. Digitized by eGangotri

चित्रः। एनं सः। [illegible] देवाः। ऋणुया। भीरुः। सः। गन्त्यो। सत्यसो। बंधान्। बद्धं। ईवा। अदिते। ना। अस्मा
कं। अस्ति। तत्। तरः। आदित्यास। सः। अति। स्कदा। पूर्वं। अस्मध्यौ। मरुता। मा। नः। हेतिः। विवस्वतः। आदि
त्याः। कृत्रिमा। शरुः। पुरा। नु। जरसः। वधीत। वि। सु। द्वेषः। वि। अंहतिं। आदित्यासः। वि। संहितं। वि
षूचीः। वि। वृहत। रपः। ५८। इति पञ्चमस्य चतुर्थो [illegible] ध्यायः॥ ॐ॥ आ। वैको। नाद्रियमेध। आ। दाव
नुष्टुमधुरवा सत्त। बाभ्रवा। रोत्स्याः। पक्षाः। अश्वमेधयोः। दर्शनस्तुतिः। [illegible] प्रप्र। स्थूना। नुष्टु। मं। द्विर
हृत्सं। तं। द्वितीयो। ङ्कि। चतुर्थ्यां। घा। गा। ध्यः। पोक। रये। कादश्यो। पंक्तौ। अपाद्धै। श्चदेवो। ढे। चैरस्त्र। यो। वा। रुणा
यो। राजा। पंचो। ना। पुरः। हन्मा। बार्हं। तं। त्रिप्रगा। था। युष्णि। गं। नुष्टुप। पुर। उष्णिगं। तं। त्वं। नः। सुदीति। पुरमी। ळो

© Dharmartha Trust J&K. Digitized by eGangotri

पु.१. तयोर्वान्यतर आग्नेयं तु त्रिष्टुब्गाथान्तं हविर्धानार्हर्यंतः प्रागाथो हविषां स्तुतिर्वौदीराथां गोपवन आत्रे
६६ यः सप्तवध्रिर्वाश्विनं विशोविशो वः पंचोनाग्नेयं स्तनु ह्युमुखावास्त्वचाश्व वारों स्वास्ति सोनुष्टु भ
आर्क्षं स्य श्रुतर्वणो दानस्तुतिर्युध्वाहि षोळशा वित्वृषं प्रमं तु द्वादशाकुरुस्तुतिः काण्वो जज्ञान
एकादश प्रगाथांतं पुरोळाशं दशा बृहत्यंतं मयंकृत्नु नवकृत्नु र्भार्गवः सौम्यमंत्यानुष्टुप् एनसंपं
दशैके घृनैधसो गायत्रं स्वादेवी त्रिष्टुब्यान्नु सोनव कुसीदी काण्वः॥ हरिः ओम्॥ आ। त्वा। रथं।
यथा। ऊतये। सुम्नाय। वर्तयामसि। तुविः कूर्मिं। ऋत्तिः सहः। इंद्र। शविष्ठ। सत्पते। तुविः श्रुष्म
तुविक्रतो। इति तुविः क्रतो। राचीवः। विश्वया। मते। आ पप्राथा। महिः त्वना। यस्य। ते। महिना। ६६

© Dharmartha Trust J&K. Digitized by eGangotri

महः।परि।ज्मा।यन्तं।ईयतुः।हस्ता।वज्रं।हिरण्ययं।विश्वानरस्य।वः।पतिं।अनानतस्य।शवसः।एवैः।

च।चर्षणीनां।ऊती।हुवे।रथानां।अभिष्टये।सदाऽवृधं।स्वःऽमीळ्हेषु।यं।नरः।नाना।हवन्ते।ऊतये।

॥३॥परःऽमात्रं।ऋचीषमं।इन्द्रं।उग्रं।सुऽराधसं।ईशानं।चित्।वसूनां।तंऽतं।इत्।राधसे।महे।इं

द्रं।चोदामि।पीतये।यः।पूर्व्यां।अनुऽस्तुतिं।ईशे।कृष्टीनां।नृतुः।न।यस्य।ते।शवसान।सख्यं।आ

नंश।मर्त्यः।नकिः।शवांसि।ते।नशत्।त्वाऽऊतासः।त्वा।युजा।अप्ऽसु।सूर्ये।महत्।धनं।जयेम।

पृत्ऽसु।वज्रिऽवः।तं।त्वा।यज्ञेभिः।ईमहे।तं।गीःऽभिः।गिर्वणःऽतम।इन्द्र।यथा।चित्।आविथ।वा

जेषु।पुरुऽमाय्यं॥२॥यस्य।ते।स्वादु।सख्यं।स्वाद्वी।प्रऽनीतिः।अद्रिऽवः।यज्ञः।वितन्तसाय्यः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. उरुः । नः । त्वं । वोन । नेः । उरुः । क्षयाय । यानुः । रुधि । उरुः । नुः । यंधि । जीव से । उरुं । नरः । भ्यः । उरुं । गवे । उरुं । रथाय । यावं
६८ थां । देव । वीतिं । मना । मे । होतः । पा । मा । वद्रूः । ह्वाः । ह्वा । नरः । सोमस्य । हव्यौ । निर्वंतिः । स्वादुः । रान यंः । ऋतः । स्रो । इं
द्रो । ते । आ । ददाह । रीः इति । ऋक्षस्य । स्तूनवि । आश्वः । मेधस्य । रोहिता । । ३ । । सुरथान् । आ । तिथिः । स्वे
सुः । अभी । श्रनः । आ । क्षे । आश्वः । मेधे । सुः । वेशः । सः । वद्रूः । अश्वान् । आ । तिथिः । स्वा । इंद्रो । नेवः । घ्रः । मनः
67 स वा । पूतः । ऋनौ । सनः । आ । ए । षु । चेन । ता । रथण्ः । वती । अंनः । ऋतः । स्रे । षु । अरत्वी । सुः । अभी । शुः । क
शाः । वती । ना । यु । ष्मे । इति । वाजः । बं । पवः । । त्रिनि । सुः । च । नाम । र्त्यः । अव । पां । अ । धि । दी । परल । । ४ । । प्र
ः । प्रा । णं । मंदत्वः । वी । राया । इंदवे । धिया । वः । मे । धः । सा । नये । पुरंः । ध्या । आ । विवा । सति । नदं । वः । ओद ६८
वस्त्रिष्टुभमिषं १

© Dharmartha Trust J&K. Digitized by eGangotri

तीनां। नदं। योयुवतीनां। पतिं। वः। अघ्न्यानां। धेनूनां। इषुध्यसि। ता। अस्य। सूदऽदोहसः। सोमं। श्रीणंति।
पृश्नयः। जन्मन्। देवानां। विशः। त्रिषु। आ। रोचने। दिवः। अभि। प्र। गोऽपतिं। गिरा। इंद्रं। अर्च। यथा। विदे।
सूनुं। सत्यस्य। सत्ऽपतिं। आ। हरयः। ससृज्रिरे। अरुषीः। अधि। बर्हिषि। यत्र। अभि। संऽनवामहे॥५॥
इंद्राय। गावः। आऽशिरं। दुदुह्रे। वज्रिणे। मधु। यत्। सीं। उपऽह्वरे। विदत्। उत्। यत्। ब्रध्नस्य। विष्टपं। गृहं। इं
द्रः। च। गन्वहि। मध्वः। पीत्वा। सचेवहि। त्रिः। सप्त। सख्युः। पदे। अर्चत। प्र। अर्चत। प्रियऽमेधासः। अर्च
त। अर्चंतु। पुत्रकाः। उत। पुरं। न। धृष्णु। अर्चत। अव। स्वराति। गर्गरः। गोधा। परि। सनिस्वनत्। पिंगा।
परि। चनिस्कदत्। इंद्राय। ब्रह्म। उत्ऽयतं। आ। यत्। पतंति। एन्यः। सुऽदुघाः। अनपऽस्फुरः। अपऽस्फु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ ते। गृभायत। सोमं। इंद्रो या। पातवे। घ। अपात्। इंद्रः। अपात्। अग्निः। विश्वे। देवाः। अमत्सत। वरेणः। इत्था। इ

६८ हा। वस्वृत। तं। आ। वः। अभि। अनूषत। वत्सं। संशिश्वरीः। इव। सुऽदेवः। असि। वरुण। यस्य। ते। सप्त। सिंधवः।

अनुऽक्षरंति। काकुदं। सूर्म्यं। सुषिरांऽइव। यः। व्यतीन्। अफाणयत्। सुऽयुक्तान्। उप। दाशुषे। तक्वः। ने

वपुः। ता। तं। इत्। उपऽमा। यः। असर्व्यत। अति। इत्। ऊं इति। शक्रः। ओहते। इंद्रः। विश्वाः। अति। द्विषः। भिनत्।

68 कनीनऽइव। आऽदनं। पव्यमानं। पुरः। जिता। अर्भकः। न। कुमारकः। अधि। तिष्ठत्। नवं। रथं। सः। पक्षत्।

महिषं। मृगं। पित्रे। मात्रे। विभुऽक्रतुं। आ। तु। सुऽशिप्र। दंऽपते। रथं। तिष्ठ। हिरण्ययं। अध। द्युक्षं। सचेव

हि। सहस्रऽपादं। अरुषं। स्वस्तिऽगां। अनेहसं। अर्थी। चित्। अस्य। सुऽधितं। यत्। एतवे। आऽव ६८

तंघेमित्थानमस्विनउपस्वराजमासते।

© Dharmartha Trust J&K. Digitized by eGangotri

अनुप्रत्नस्योकसः पूर्वामनुप्रयतिं

नेयंति। दावने। ते। प्रियमेधासः। एषां। वृक्तबर्हिषः। हितप्रयसः। आशत॥ ॥ यः। राजा। चर्षणीनां।
याता। रथेभिः। अध्रिगुः। विश्वासां। तरुता। पृतनानां। ज्येष्ठः। यः। वृत्रहा। गृणे। इंद्रं। तं। शुंभ। पुरुह
न्मन्। अवसे। यस्य। द्विता। विधर्तरि। हस्ताय। वज्रः। प्रति। धायि। दर्शतः। महः। दिवे। न। सूर्यः।
नकिष्टंकर्मणानशत् यः। चकार। सदावृधं। इंद्रं। न। यज्ञैः। विश्वगूर्तं। ऋभ्वसं। अधृष्टं। धृष्णुओजसं। अषाळ्हं।
उग्रं। पृतनासु। ससहिं। यस्मिन्। महीः। उरुज्रयः। सं। धेनवः। जायमाने। अनोनवुः। द्यावः। क्षामः।
अनोनवुः। यत्। द्यावः। इंद्र। ते। शतं। शतं। भूमीः। उत। स्युरिति स्युः। न। त्वा। वज्रिन्। सहस्रं। सूर्याः।
अनु। न। जातं। अष्ट। रोदसी इति॥५॥ आ। पप्राथ। महिना। वृष्ण्या। वृषन्। विश्वा। शविष्ठ। शवसा।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. अस्मान्। अद्य। मघऽवन्। गोऽमति। व्रजे। वज्रिन्। चित्राभिः। ऊतिऽभिः। नासीं। अदेवः। आपत्। इषं। दीर्घा
६९ योऽइति दीर्घऽआयो। मर्त्यः। एतऽग्वा। चित्। यः। एतशा। युयोजते। हरी इति। इंद्रः। युयोजते। नं। वः। मुहः
नो महाय्यं। इंद्रं। दुध्य। स्वक्षणिं। यः। शश्वत। धेषुयः। आः। अरणेषु। हव्यः। वाजेषु। अस्ति। हव्यः। उत। ऊं इति। सु। नः। व
69 सोऽइति। मुहः। मदश। रखा। शूर। राधसे। क्रतं। ऊं इति। सु। मुलः। मघऽवन्। मघ। तये। उत। इंद्र। अवसे। महः। त्वं
नः। इंद्र। ऋतऽयुः। त्वा। निदः। नि। तं। पासि। मध्या। वसि। द्यानु। विऽन्रम्णा। ऊर्वोः। नि। दासं। शिश्नथः। हथैः।
॥ ९॥ अन्यऽव्रतं। अमानुषं। अयज्वानं। अदेवऽयुं। अव। स्वः। सखा। दुधुवीत। पर्वतः। सुऽघ्नाय। दस्युं।
सन इंद्र पर्वतः। ॥ ३॥ आसां। हस्तो। शग्धि। द्राव्ने। धानां। संऽगृभाय। अस्मऽयुः। द्विः। सं। गृभाय। अस्मऽयुः। स ६९
नी न।

© Dharmartha Trust J&K. Digitized by eGangotri

स्वायः । कर्तुं । इन्धता । कृथा । रा । धा । मा । शं । स्या । उपः । स्नुलिं । भो । जः । सूरिः । यः । अहः । सूरिऽभिः । समहा । ऋषि
ऽभिः । बर्हिष्मन्ऽभिः । स्तविष्यसे । यत् । इत्थं । एकंऽएकं । इत्था । शरा । न । सा । नः । परा । ददः । कर्ण । ग्रहा । आमघ
ऽया । शौरः । देव्यः । वसां । नः । त्रिऽभ्यः । आ । अनयत् । अजो । सूरिः । न । धालेवा ॥ ३ ॥ ० ॥ महःऽभिः । पाहि । त्वं नो अग्ने
विश्वस्याः । अरातेः । उत । द्विषः । मर्त्यस्य । नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजातः । त्वं । इत् । अ
सि । क्षपाऽवान् । त्वः । नः । विश्वेभिः । देवेभिः । ऊर्जः । नपात् । भद्रऽशोचे । रयिं । देहि । विश्वऽवारं । न । तं
अग्ने । अरातयः । मर्त्यं । युवंत । रायः । यं । त्रायसे । दाश्वांसं । यं । त्वं । विप्र । मेधऽसातौ । अग्ने । हिनोषि
धनाय । सः । तवा । ऊती । गोषु । गंता ॥ ३ ॥ त्वं । रयिं । पुरुऽवीरं । अग्ने । दाशुषे । मर्ताय । प्र । नः । नय । व

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. स्वः। अच्छ। उरुष्य। नः। मा। परा। दाः। अघऽयतः। जातऽवेदः। दुः। आध्ये। मर्त्याय। अग्ने। माकिः। नः। देव। त्वा। दु
७० तिं। अदेवः। युयोत। त्वं। ईशिषे। वसूनां। सः। नः। वस्वः। उप। मासि। ऊर्जः। नपात्। माहिनस्य। सखे। वसो
इति। जरि॰तृऽभ्यः। अच्छ। नः। शीरऽशोचिषं। गिरः। यन्तु। दर्शतं। अच्छ। यज्ञासः। नमसा। पुरुऽवसुं। पुरुऽ
70 प्रशस्तं। ऊतये। ३३। अग्निं। सूनुं। सहसः। जातऽवेदसं। दानाय। वार्याणां। द्विता। यः। भूत्। अमृतः।
मर्त्येषु। आ। होता। मन्द्रऽतमः। विशि। अग्निं। वः। देवऽयज्यया। अग्निं। प्रऽयति। अध्वरे। अग्निं। धीषु।
प्रथमं। अग्निं। अर्वति। अग्निं। क्षैत्राय। साधसे। अग्निः। इषां। सख्यं। ददातु। नः। ईशे। यः। वार्याणां।
अग्निं। तोके। तनये। शश्वत्। ईमहे। वसुं। सन्तं। तनूऽपां। अग्निं। ईळिष्व। अवसे। गाथाभिः। शीरऽशोचिषं। ७०
संतं।

© Dharmartha Trust J&K. Digitized by eGangotri

अग्निं। राये। पुरुऽमीळ्ह। श्रुतं। नरः। अग्निं। सुऽदीतये। छर्दिः। अग्निं। द्वेषः। योतवै। नः। गृणीमसि। अ
ग्निं। शं। योः। च। दातवे। विश्वासु। विक्षु। अविताऽइव। हव्यः। भुवत्। वस्तुः। ऋषूणां॥ १३॥ हविः। कृ
णुध्वं। आ। गमत्। अध्वर्युः। वनते। पुनरिति। विद्वान्। अस्य। प्रऽशासनं। नि। तिग्मं। अभि।
अंशुं। सीदत्। होता। मनौ। अधि। जुषाणः। अस्य। सख्यं। अंतः। इच्छंति। तं। जने। रुद्रं। परः। मनीष
या। गृभ्णंति। जिह्वया। ससं। जामि। अतीतपे। धनुः। वयःऽधाः। अरुहत्। वनं। दृषदं। जिह्वया।
आ। अवधीत्। चरन्। वत्सः। रुशन्। इह। निऽदातारं। न। विंदते। वेति। स्तोतवे। अम्ब्यं॥ १४॥
उतोइति। नु। अस्य। यत्। महत्। अश्वऽवत्। योजनं। बृहत्। दामा। रथस्य। ददृशे। दुहंति।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. सप्ताऽएकां।उप।द्या।पंचा।स्तृ।अतः।तीर्थे।सिं।धोः।अधि।स्वरे।आ।दशः।भिः।वि।वस्वतः।इंद्रः।कोशं।
७३ अचुच्यवीत।खेदया।त्रिऽरत्ना।दिवः।परि।त्रिऽधातुः।अध्वरं।जूर्णिः।एति।नवीयसी।मध्वा।हो
तारः।अंजते।सिंचंति।नमसा।अयतं।उत्साऽचक्रं।परिऽज्मानं।नीचीनऽबारं।अक्षितं।१५।अ
भिः।आ।रां।इता।अद्वयः।निःसिक्तं।पुष्करे।मधु।अवतस्य।विऽसर्जने।गावः।उप।अवत।अवतं।
महीइति।यज्ञस्य।रप्सुदा।उभा।कर्णा।हिरण्यया।आ।सुते।सिंचत।श्रियं।रोदस्योः।अभिःश्रियं।
रसा।दधीत।वृषभं।ते।जानत।स्वं।ओक्यं।सं।वत्सासः।न।मातृऽभिः।मिथः।न।संत।जामिऽभिः
उपा।स्रक्वेषु।बप्सतः।कृण्वते।धरुणं।दिवि।इंद्रे।अग्ना।नमः।स्वः।रितिस्वः।१६।अधुक्षत।पिप्यु ७१

71

© Dharmartha Trust J&K. Digitized by eGangotri

उतोन्वस्यय

षीं। इषं। ऊर्जं। सप्तऽपदीं। अरिः। सूर्यस्य। सप्त। रश्मिऽभिः। सोमस्य। मित्रावरुणा। उत्ऽइता। सूरेः। आ।
दृद्रा न ता। आतुरस्य। भेषजं॥ पदं। हयेलस्य। निऽधान्यं। परि। घ्रां। जिह्मया। अतनन्त॥ ३७॥ उत्
ईराथां। ऋतऽयते। युजाथां। अश्विना। रथं। अंति। सत्। भूतु। वां। अवः। निऽमिषः। चित्। जवीयसा।
रथेन। आ। यातं। अश्विना॥ उप। स्तृणीतं। अत्रये। हिमेन। घर्मं। अश्विना॥ कुह। स्थः। कुह। ज
ग्मथुः। कुह। श्येनाऽइव। पेतथुः॥ यत्। अद्य। कर्हि। कर्हि। चित्। शुश्रूयातं। इमं। हवं॥ ३८॥ अ
श्विना। यामऽहूतमा। नेदिष्ठं। यामि। आप्यं॥ अवंतां। अत्रये। गृहं। कृणुतं। युवं। अश्विना॥ व
रथे इति। अग्निं। आऽतपः। वदति। वल्गु। अत्रये॥ प्र। सप्तऽवध्रिः। आऽशसा। धारां। अग्नेः। अश

© Dharmartha Trust J&K. Digitized by eGangotri

प.१. प्रत्ना।०।इह।आ।गंतारा।वृषण्वसू इति वृषण्ऽवसू।श्रृणुतं।मे।इमं।हवं।०।१३।किं।इदं।वां।पुराणऽव
७२ त्।जरतोःऽइव।शस्यते।०।समानं।वां।सऽजात्यं।समानः।बंधुः।अश्विना।०।यः।वां।रजांसि।अ
श्विना।रथः।विऽयाति।रोदसी इति।०।आ।नः।गव्येभिः।अश्व्यैः।सहस्त्रैः।उप।गच्छतं।मा।०। नोगव्येभिरश्व्यैः
72 सहस्त्रेभिः।अति।ख्यतं।०।अरुणऽप्सुः।उषाः।अभूत्।अकः।ज्योतिः।ऋतऽवरी।०।अश्विना।
सु।विऽचाकशत्।वृक्षं।परशुमान्ऽइव।०।पुरं।न।धृष्णो इति।आ।रुज।कृष्णया।बाधितः।वि
शा।०।।२०।।विशःऽविशः।वः।अतिथिं।वाजऽयंतः।पुरुऽप्रियं।अग्निं।वः।दुर्यं।वचः।स्तुषे।शूष
स्य।मन्मऽभिः।यं।जनासः।हविष्मंतः।मित्रं।न।सर्पिःऽआसुतिं।प्रऽशंसंति।प्रशस्तिऽभिः। ७२

© Dharmartha Trust J&K. Digitized by eGangotri

पन्यांसं।जातऽवेदसं।यः।देवऽताति।उत्ऽयता।हव्यानि।ऐरयत्।दिवि।आ।अगन्म।वृत्रहन्ऽत
मं।ज्येष्ठं।अग्निं।आनवं।यस्य।श्रुतर्वा।बृहन्।आर्क्षः।अनीके।एधते।अमृतं।जातऽवेदसं।ति
रः।तमांसि।दर्शतं।घृतऽआहवनं।ईड्यं।।२१।।सऽबाधः।यं।जनाः।इमे।अग्निं।हव्येभिः।ईळते।
जुह्वानासः।यतऽस्रुचः।इयं।ते।नव्यसी।मतिः।अग्ने।अधायि।अस्मत्।आ।मंद्र।सुऽजात।सु
क्रतो इति सुऽक्रतो।अमूर।दस्म।अतिथे।सा।ते।अग्ने।शंऽतमा।चनिष्ठा।भवतु।प्रिया।तया।व
र्धस्व।सुऽस्तुतः।सा।द्युम्नैः।द्युम्निनी।बृहत्।उप।उप।श्रवसि।श्रवः।दधीत।वृत्रऽतूर्ये।अश्वं।इत्
गोऽरथं।प्राः।त्वेषं।इंद्रं।न।सत्ऽपतिं।यस्य।श्रवांसि।तूर्वथ।पन्यंऽपन्यं।च।कृष्टयः।।२२।।यं।त्वा।

© Dharmartha Trust J&K. Digitized by eGangotri

५५. गोपवंनः। गिरा। चनिष्ठत्। अग्ने। अंगिरः। सः। पावक। श्रुधि। हवं। यं। त्वा। जनाः। सः। ईळते। सः। बा
७३ धःऽवाजं। सातये। सः। बोधि। वृत्रऽतूर्ये। अहं। हुवानः। आर्क्षे। श्रुतर्वणि। मदऽच्युति। शर्द्धांसिऽ
इव। स्तुकाऽविनां। मृक्षा। शीर्षा। चतुर्णां। मां। च[illegible]त्वारः। आशवः। शविष्ठस्य। द्रवित्नवः। सु
रथासः। अभि। प्रयः। वक्षन्। वयः। न। तुग्र्यं। सत्यं। इत्। त्वा। महे। नदि। परुष्णि। अव। देदिशं। न।
ईं। आपः। अश्वऽदातरः। शविष्ठात्। अस्ति। मर्त्यः।। २२।। युक्ष्व। हि। देवऽहूतमान्। अश्वान्। अ
ग्ने। रथीःऽइव। नि। होता। पूर्व्यः। सदः। उत। नः। देव। देवान्। अच्छ। वोचः। विदुःऽतरः। श्रत्। विश्वा। वा
र्या। कृधि। त्वं। ह। यत्। यविष्ठ्य। सहसः। सूनो इति। आऽहुत। ऋतऽवा। यज्ञियः। भुवः। अयं। अ ७३

© Dharmartha Trust J&K. Digitized by eGangotri

ग्निः। सहस्रिणः। वाजस्य। शतिनः। पतिः। मूर्द्धा। कविः। रयीणां। तं। नेमिं। ऋभवः। यथा। आ। नम
स्व। सहूतिऽभिः। नेदीयः। यज्ञं। अंगिरः॥ २४॥ तस्मै। नूनं। अभिऽद्यवे। वाचा। विऽरूप। नित्यया।
वृष्णे। चोदस्व। सुऽस्तुतिं। कं। ऊं इति। स्वित्। अस्य। सेनया। अग्नेः। अपाकऽचक्षसः। पणिं। गोषु।
स्तरामहे। मा। नः। देवानां। विशः। प्रऽस्नातीःऽइव। उस्राः। कृशं। न। हासुः। अघ्न्याः। मा। नः। समस्य।
दुःऽध्यः। परिऽद्वेषसः। अंहतिः। ऊर्मिः। न। नावं। आ। वधीत्। नमः। ते। अग्ने। ओजसे। गृणंति। दे
व। कृष्टयः। अमैः। अमित्रं। अर्दय॥ २५॥ कुवित्। सु। नः। गोऽइष्टये। अग्ने। संऽवेषिषः। रयिं। उरुऽ
कृत्। उरु। नः। कृधि। मा। नः। अस्मिन्। महाऽधने। परा। वर्क्। भारऽभृत्। यथा। संऽवर्गं। सं। रयिं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. जय। अन्यं। अस्मत्। भियै। इयं। अग्ने। सिसक्तु। दुच्छुना। वर्द्ध। नः। अमऽवत्। शवः। यस्य।
७४ अजुष्टन्। नमस्विनः। शमी। अदुःऽमखस्य। वा। तं। घ। इत्। अग्निः। वृधा। अवति। परस्याः।
75 अधि। संऽवतः। अवरान्। अभि। आ। तर। यत्र। अहं। अस्मि। तान्। अव। विद्म। हि। ते। पुरा। व
यं। अग्ने। पितुः। यथा। अवसः। अध। ते। सुम्नं। ईमहे। रधा। इमं। नु। मायिनं। हुवे। इन्द्रं। ईशानं।
ओजसा। मरुत्वन्तं। न। वृञ्जसे। अयं। इन्द्रः। मरुत्ऽसखा। वि। वृत्रस्य। अभिनत्। शिरः। वज्रे
ण। शतऽपर्वणा। वव्रधानः। मरुत्ऽसखा। इन्द्रः। वि। वृत्रं। ऐरयत्। सृजन्। समुद्रियाः। अपः। अ
यं। ह। येन। वै। इदं। स्वः। मरुत्वता। जितं। इन्द्रेण। सोमऽपीतये। मरुत्वन्तं। ऋजीषिणं। ओजस्वन्तं। ७४

© Dharmartha Trust J&K. Digitized by eGangotri

अस्य सोमस्य पीतये १

विऽरप्शिनं। इंद्रं। गीःऽभिः। हवामहे। इंद्रं। प्रत्नेन। मन्मना। मरुत्वंतं। हवामहे। ॥ २ ॥ मरुत्वान्। इंद्र।

मीढ्वः। पिब। सोमं। शतक्रतो इति शतऽक्रतो। अस्मिन्। यज्ञे। पुरुऽस्तुत। तुभ्य। इत्। इंद्र। मरुत्वते। सु

ताः। सोमासः। अद्रिऽवः। हृदा। हूयंते। उक्थिनः। पिब। इत्। इंद्र। मरुत्ऽभिः। सखा। सुतं। सोमं। दिविष्टिषु।

वज्रं। शिशानः। ओजसा। उत्ऽतिष्ठन्। ओजसा। सह। पीत्वी। शिप्रे इति। अवेपयः। सोमं। इंद्र। चमू

इति। सुतं। ॥ ० ॥ ऋक्षमाणं। अकृपेतां। इंद्र। यत्। दस्युऽहा। अभवः। वाचं। अष्टाऽपदीं। अहां। नवऽस्रक्तिं।

ऋतऽस्पृशं। इंद्रात्। परि। तन्वं। ममे। ॥ २ ॥ जज्ञानः। नु। शतऽक्रतुः। वि। पृच्छत्। इति। मातरं। कः। उग्राः।

के। ह। शृण्विरे। आत्। ईं। शवसी। अब्रवीत्। और्णऽवाभं। अहिशुवं। तं। पुत्र। संतु। निःऽस्तुरः। सं। इत्।

प॰ प॰ तां । वृत्रऽहा । अविदत् । त्वो । अरान्ऽइव । स्वेद्या । प्रऽवृद्धः । दस्युऽहा । अभवत् ।२। एकया । प्र
७५ तिऽधा । अपिबत् । साकं । सरांसि । त्रिंशतं । इंद्रः । सोमस्य । काणुका । अभि । गंधर्वं । अतृणत् ।
75 अबुध्नेषु । रजःऽसु । आ । इंद्रः । ब्रह्मऽभ्यः । इत् । वृधे ।३॥ निः । अविध्यत् । गिरिऽभ्यः । आ । धार
यत् । पक्वं । ओदनं । इंद्रः । बुंदं । सुऽआततं । शतऽब्रध्नः । इषुः । तव । सहस्रऽपर्णः । एकः । इत् । यं । इं
द्र । चकृषे । युजं । तेन । स्तोतृऽभ्यः । आ । भर । नृऽभ्यः । नारिऽभ्यः । अत्तवे । सद्यः । जातः । ऋभुऽस्थि
र । एता । च्यौत्ना । नि । ते । कृता । वर्षिष्ठानि । परीणसा । हृदा । वीळु । अधारयः । विश्वा । इत् । ता ।
विष्णुः । आ । अभरत् । उरुऽक्रमः । त्वाऽइषितः । शतं । महिषान् । क्षीरऽपाकं । ओदनं । वराहं । इं ७५

© Dharmartha Trust J&K. Digitized by eGangotri

उभा ते बाहू

द्रः । एमुषं । तुविऽक्षं । ते । सुऽकृतं । सुऽमयं । धनुः । साधुः । बुंदः । हिरण्ययः । ० । रण्या । सुऽसंस्कृता ।
ऋदुऽपे । चित् । ऋदुऽवृधा ॥ ३ ॥ पुरोळाशं । नः । अंधसः । इंद्र । सहस्रं । आ । भर । शतिना । च । शूर ।
गोनां । आ । नः । भर । विऽअंजनं । गां । अश्वं । अभिऽअंजनं । सचा । मना । हिरण्यया । उत । नः । कर्णऽ
शोभना । पुरूणि । धृष्णो इति । आ । भर । त्वं । हि । शृण्विषे । वसो इति । नकीं । वृधीकः । इंद्र । ते । न ।
न । सुऽसाः । सुऽदाः । उत । न । अन्यः । त्वत् । शूर । वाघतः । नकीं । इंद्रः । निऽकर्तवे । न । शक्रः । परिऽश
क्तवे । विश्वं । शृणोति । पश्यति ॥ ३ ॥ सः । मन्युं । मर्त्यानां । अदब्धः । नि । चिकीषते । पुरा । निदः ।
चिकीषते । क्रत्वः । इत । पूर्णं । उदरं । तुरस्य । अस्ति । विधतः । वृत्रऽघ्नः । सोमऽपाव्नः । त्वे इति । वसु

प.ब. त्रि। संऽगृता। विभ्वा। च। सोम। सौभगा। सुऽदानु। अपरिऽकृता। त्वां। इत्। यवऽयुः। मम। कामः।
७९ गव्युः। हिरण्यऽयुः। त्वां। अश्वऽयुः। आ। ईषते। तव। इत्। इंद्र। अहं। आऽशसा। हस्ते। दात्रं। चन।
आ। ददे। दिनस्य। वा। मघऽवन्। संऽभृतस्य। वा। पूर्द्धि। यवस्य। काशिना॥ ३२॥ अयं। कृ
नुः। अगृभीतः। विश्वऽजित्। उत्ऽभित्। इत्। सोमः। ऋषिः। विप्रः। काव्येन। अभि। ऊर्णोति। यत्।
नग्नं। भिषक्ति। विश्वं। यत्। तुरं। प्र। ईं। अंधः। ख्यत्। निः। श्रोणः। भूत्। त्वं। सोम। तनूकृत्ऽभ्यः।
द्वेषःऽभ्यः। अन्यऽकृतेभ्यः। उरु। यंता। असि। वरूथं। त्वं। चित्ती। तव। दक्षैः। दिवः। आ। पृथिव्याः।
ऋजीषिन्। यावीः। अघस्य। चित्। द्वेषः। अर्थिनः। यंति। च। इत्। अर्थं। गच्छान्। इत्। ददुषः। रातिं। ७९

© Dharmartha Trust J&K. Digitized by eGangotri

वरज्युः।तृष्यतः।कामं॥३३॥विदत्।यत्।पूर्व्यं।नष्टं।उत्।ईं।ऋतऽयुं।ईरयत्।प्र।ईं।आयुः।
तारीत्।अतीर्णं।सुऽशेवः।नः।मृळयाकुः।अदृप्तऽक्रतुः।अवातः।भव।नः।सोम।शं।हृदे।मा।
नः।सोम।सं।वीविजः।मा।वि।बीभिषथाः।राजन्।मा।नः।हार्दि।त्विषा।वधीः।अव।यत्।स्वे।
सधऽस्थे।देवानां।दुःऽमतीः।ईक्षे।राजन्।अप।द्विषः।सेध।मीढ्वः।अप।स्रिधः।सेध॥३४॥न
हि।अन्यं।बळा।अकरं।मर्डितारं।शतक्रतो इति शतऽक्रतो।त्वं।नः।इंद्र।मृळय।यः।नः।शश्वत्।
सःनःइंद्रमृळय पुरा।आविथ।अमृध्रः।वाजऽसातये।ँ।किं।अंग।रध्रऽचोदनः।सुन्वानस्य।अविता।इत्।अ
य। सि।कुवित्।सु।इंद्र।नः।शकः।इंद्र।प्र।नः।रथं।अव।पश्चात्।चित्।संतं।अद्रिऽवः।पुरस्तात्।ए

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. नं।मे।रुधि।हं।नो।इति।नु।किं।आस।से।प्रथ।मं।नः।रथो।रुधि।उपऽमं।वाजऽयुः।श्रवः।रूपा।अव।
७१ नः।वाजऽयुं।रथं।सुऽकरं।ते।किं।इत।परि।अस्मान्।सु।जिग्युषः।रुधि।इंद्रा।दद्यस्व।पूः।असि।
मघा।ते।एति।निःऽकृतं।इयं।धीः।ऋत्वियऽवती।मासी।अव।घो।आ।भा।कृ।उ।वीं।का।षा।हि।ते।
धनो।अपः।आ।वृक्ताः।अरत्न।यः।तुरीयं।नाम।यज्ञियं।यदा।करः।तत्।तु।रम।सि।आत्।इत्।प
तिः।नः।ओ।हसे।अवीर।धत्।वः।अम।ताः।अमं।दीत्।अे।कः।पूः।देवाः।तु।ता।याः।चा।दे।वीः।नस्सै।
ऊं।इति।राधः।ऋण।तं।प्रऽशास्तं।बा।उद्धा।ण।क्ष्युः।मं।तं।चित्रं।ग्ना।मं।सा।ग।भाया।म।हाऽहस्ती।दक्षि
णेन।वि।सा।हि।त्वा।तु।विऽकूर्मिं।तु।विऽदेष्णं।तु।विऽमघं।तु।विऽमात्रं।अवःऽभिः।नहि।त्वा।शूर।दे ७७

प्रातर्म०।३८।आ तू न इंद्र।

© Dharmartha Trust J&K. Digitized by eGangotri

वाः। ना। मन्त्रीसः। दिः। स॒तं। भी। मं। ना। गां। वारयंते। ग। ई॒शानं। व॒स्वः। स्वऽराजं। ना। राधसा। मह्विष
ता। नः। प्र। स्तोषत। उप। गा। स्त्रिषत। श्रवत। सामं। गीयमानं। अभि। राधसा। जुगुरत। इ गीद औंत्वोमर २
क्षिणेन। अभि। सव्येन। प्र। मृश। इंद्र। मा। नः। वसोः। निः। भाक्। उप। क्रमस्व। आ। भर। धृषता। धृ
२ ष्णो। इति। जनानां। अदाः। भूः। तस्य। वेदः। इंद्र। यः। कुं। इति। नु। तो। अस्ति। वाजः। विप्रेभिः। सनि। वः।
अस्माभिः। सुतं। सनुहि। सघः। जुवः। तो। वाजाः। अस्मभ्यं। विश्वऽचंद्राः। वशैः। च। मक्षु। जरंते।
। द्व। इति षष्ठाष्टके पंचमोध्यायः॥ ओं नमः॥ आ प्र देवानां वैश्वदेवं त्रिष्टमुशना काव्य आग्नेयमा
मेरुद्गम आश्विनं धु भाहि पंच कोवा काण्वो जो गालं धुम्नी षट् वासिष्ठो वा धुम्नीकः प्रियमेधो

© Dharmartha Trust J&K. Digitized by eGangotri

प.व. बाग्रा गाथं हतं वो दस्मन्नो धां बृहदिंद्राय सत्तं न्रमेधपुरुमेधौ द्यनुष्टुब्बृहस्यंतं मानो विश्वा सु
७८ षट्कं न्या वाः स मां त्रेय्य पाले ति हासे ऐंद्र आनुष्टुभं द्विपंत्यादिपां तं त्रयास्त्रिंशं छुत कक्षः सु
कक्षो वा यानुष्टुबुड्डु चतु त्रिंशात्सु कक्षौ सैंद्रा र्भ वी गौ ऌर्ध यति द्वादशं बिंदुः पूतदक्षो वा मारुतमा
78 त्वानवति रश्वि रां गिरस आनुष्टुभं मस्मै सेकां पुनानो वा मारुतिस्त्रे ष्टुभं चतुर्थी विराड्व्या
मीति मारुतः पादः परे द्वा बार्हस्पत्या याइंद्रपंचो नारभः कारयपो बार्हतं मतिजगत्सु परिष्टाद्बृ
हत्यावति जगती त्रिष्टुपं जगती त्यं तं ततः॥ ॥ हरिः ओम्॥ आ। प्रा ऽद्ववा। परा ऽवतः। अर्वा ऽवतः। वृ
त्र ऽहन्। मध्वः। प्रति। प्रऽभर्मणि। सुतासः। मादयिष्णवः। पिब। दधृक्। यथा। ओ चिषा इषाम्। मुं ७८

तीव्राः सोमास आगहि

© Dharmartha Trust J&K. Digitized by eGangotri

हस्व। आ। तु। ऊं इति। नः। अरं। वराय। मन्यवे। भुवत्। ते। इंद्र। शं। हृदे। आ। तु। अशत्रो इति। आ। गहि। नि।
उक्थानि। च। हूयसे। उपऽमे। रोचने। दिवः। तुभ्यं। अयं। अद्रिऽभिः। सुतः। गोऽभिः। श्रीतः। मदाय। कं। प्र।
सोमः। इंद्र। हूयते। ईंद्र। श्रुधि। सु। मे। हवं। अस्मे इति। सुतस्य। गोऽमतः। वि। पीतिं। तृप्तिं। अश्नुहि। य।
इंद्र। चमसेषु। आ। सोमः। चमूषु। ते। सुतः। पिब। इत्। अस्य। त्वं। ईशिषे। यः। अपऽसु। चंद्रमाःऽइव। सो
पिबे· मः। चमूषु। ददृशे। ०। यं। तु। श्येनः। पदा। आ। अभरत्। तिरः। रजांसि। अस्पृतं। ०। ३। देवानां। इत्। पिबें·
अवः। महत्। तत्। आ। वृणीमहे। वयं। वृष्णां। अस्मभ्यं। ऊतये। ते। नः। संतु। युजः। सदा। ०। वृधासः। वरुणो मित्रो·
च। प्रऽचेतसः। अति। नः। विष्पिता। पुरु। नौभिः। अपः। न। पर्षथ। यूयं। ऋतस्य। रथ्यः। वामं। नः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष.

७९ अस्तु।अर्यमन्।या।मां।वरुणा।शस्यां।या।मां।हि।आऽवरणीमहे।या।मस्या।हि।प्रऽचेतसः।ईशाना।सः।रि
शादसः।नाई।आदित्याः।अपस्या।यत्।श।वयं।इता।वः।सुऽदानवः।क्षियंतः।यांतः।अध्वन्।आ।
देवाः।वरूधाय।हूमहे।अधि।नः।इंद्राएषां।विष्णो इति।सऽजात्यानां।इता।मरुतः।अश्विना।प्रा।भ्रा
तृऽत्वं।सुऽदानवः।अध।द्विता।समान्या।मातुः।गर्भे।भरामहे।०।अध।चित्।वः।उत।ब्रुवे।४।प्रेष्ठं। पूर्वं हिं बासुह
वः।अतिथिं।स्तुषे।मित्रंऽइव।प्रियं।अग्निं।रथं।न।वेद्यं।कविंऽइव।प्रऽचेतसं।यं।देवासः।अध।द्वि नयइंद्रज्येष्ठा अभिप यवः।
ता।नि।मर्त्येषु।आऽदधुः।त्वं।यविष्ठ।दाशुषः।नॄन्।पाहि।शृणुधि।गिरः।रक्ष।तोकं।उत।त्मना।क
या।ते।अग्ने।अंगिरः।ऊर्जः।नपात्।उप।स्तुतिं।वराय।देव।मन्यवे।दाशेम।कस्य।मनसा।यज्ञस्य। ७९

79

© Dharmartha Trust J&K. Digitized by eGangotri

सहसः। यहो इति। कत्। ऊं इति। वोचे। इदं। नमः॥ ८॥ अध। त्वं। हि। नः। करः। विश्वाः। अस्मभ्यं। सुऽक्षितीः।
वाजेऽद्रविणसः। गिरः। कस्य। नूनं। परीणसः। धियः। जिन्वसि। दंऽपते। गोऽसाता। यस्य। ते। गिरः। तं।
मर्जयंत। सुऽक्रतुं। पुरःऽयावानं। आजिषु। स्वेषु। क्षयेषु। वाजिनं। क्षेति। क्षेमेभिः। साधुऽभिः। नकिः। घ्नं यं।
ति। हंति। यः। अग्ने। सुऽवीरः। एधते॥ ९॥ आ। मे। हवं। नासत्या। अश्विना। गच्छतं। युवं। मध्वः। सोमस्य।
पीतये। इमं। मे। स्तोमं। अश्विना। इमं। मे। शृणुतं। हवं॥ २॥ अयं। वां। कृष्णः। अश्विना। हवते। वाजिनी मध्वः॰
वसू इति वाजिनीऽवसू॥ ३॥ शृणुतं। जरितुः। हवं। कृष्णस्य। स्तुवतः। नरा॥ ४॥ छर्दिः। यंतं। अदाभ्यं।
विप्राय। स्तुवते। नरा॥ ५॥ गच्छतं। दाशुषः। गृहं। इत्था। स्तुवतः। अश्विना॥ ६॥ युंजाथां। रासभं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. [illegible]रथे।वीळुऽअंगे।वृषण्वसू इति वृषण्ऽवसू॥ त्रिऽवंधुरेण।त्रिऽवृता।रथेन।आ।यातं।अश्वि
८० ना॥ नु।मे।गिरः।नासत्या।अश्विना।प्र।अवतं।युवं॥ ॥ उभा।हि।दस्रा।भिषजा।मयःऽभुवा
उभा।दक्षस्य।वचसः।बभूवथुः।आ।वां।विश्वकः।हवते।तनूऽकृथे।मा।नः।वि।यौष्टं।सख्या।मु
80 मोचतं।कथा।नूनं।वां।विऽमनाः।उप।स्तवत्।युवं।धियं।ददथुः।वस्यःऽइष्टये॥ युवं।हि।स्मा।पु तौ.धं.
रुऽभुजा।इमं।एधतुं।विष्णाप्वे।ददथुः।वस्यःऽइष्टये॥ युता।स्वां।वीरं।धनऽसां।ऋजीषिणं।दूरे।चि
त्।संतं।अवसा।हवामहे।यस्य।स्वादिष्ठा।सुऽमतिः।पितुः।यथा॥ ऋते।न।देवः।सविता।शंऽआ मानोवि.
यते।ऋतस्य।शृंगं।उर्विया।विऽपप्रथे।ऋतं।ससाह।महि।चित्।पृतन्यतः॥ ॥ द्युम्नी।वां।स्तो ८०

© Dharmartha Trust J&K. Digitized by eGangotri

ओं आ वां विश्वाभिरूतिभिः
प्रियमेधा अहूषत। ३

आ नूनं यातमश्विना ४ ३ मधुमंतमश्विना बर्हिः सीद तं

मः। अश्विना। कविंः। ना। सत्यौ। आ। गतं। मध्वः। सुतस्य। सः। दिवि। प्रियः। नरा। पातं। गौरौऽइव। इरि
णे। पिबतं। घर्मं। मधुऽमंतं। अश्विना। आ। बर्हिः। सीदतं। नरा। ता। मंदसाना। मनुषः। दुरोणे। आ। नि।
पातं। वेदसा। वयः। ँता। वह्निंः। यातं। उपऽव्रजः। बर्हिषः। जुष्टं। यज्ञं। दिविष्टिषु। पिबतं। सोमं। सुऽम
न्मना। वृधाना। उप। सुऽस्तुतिं। दिवः। गंतं। गौरौऽइव। इरिणं। अश्वेभिः। प्रुषितप्सुऽभिः। दस्रा।
पातं सोमम् ऋ हिरण्यवर्तनी इति हिरण्यऽवर्तनी। शुभः। पती इति। ँ विपन्यवः। विप्रासः। वाजऽसातये। पुरुऽदं तावत् नूदस्रा
तावृधा। व ससा। धिया। अश्विना। श्रुष्टी। आ। गतं। ३ नः। वः। दस्मं। ऋतिऽसहं। वसोः। मंदानं। अंधसः। अ
यं हि वां हवा भि। वत्सं। न। स्वसरेषु। धेनवः। इंद्रं। गीःऽभिः। नवामहे। द्युक्षं। सुऽदानुं। तविषीभिः। आऽवृतं। गिरिं।
महे ३

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. न। पूर्व्यः। ओजसा। क्षुऽमन्तं। वाजं। शतिनं। सहस्रिणं। मक्षु। गोऽमन्तं। ईमहे। न। त्वा। बृहन्तः। अद्रयः।
८१ वरन्ते। इन्द्र। वीळवः। यत्। दित्ससि। स्तुवते। माऽवते। वसु। नकिः। तत्। आ। मिनाति। ते। योद्धा।
असि। क्रत्वा। शवसा। उत। दंसना। विश्वा। जाता। अभि। मज्मना। आ। त्वा। अयं। अर्कः। ऊत
ये। ववर्त्तति। यं। गोतमाः। अजीजनन्। प्र। हि। रिरिक्षे। ओजसा। दिवः। अन्तेभ्यः। परि। न। त्वा। विव्या
च। रजः। इन्द्र। पार्थिवं। अनु। स्वधां। ववक्षिथ। नकिः। परिष्टिः। मघऽवन्। मघस्य। ते। यत्। दाशुषे।
दशस्यसि। अस्माकं। बोधि। उचथस्य। चोदिता। मंहिष्ठः। वाजऽसातये॥ ११॥ बृहत्। इन्द्राय। गा
यत। मरुतः। वृत्रहन्ऽतमं। येन। ज्योतिः। अजनयन्। ऋतऽवृधः। देवं। देवाय। जागृवि। अप। अप ८१

81

© Dharmartha Trust J&K. Digitized by eGangotri

मत्। अभिऽशस्तीः। अप। अस्थिःऽहा। अथ। इन्द्रः। द्युम्नी। आ। अभवत्। देवाः। ते। इन्द्र। सख्याय। येमिरे। बृहद्भा

नो इति बृहत्ऽभानो। मरुत्ऽगण। प्र। वः। इन्द्राय। बृहते। मरुतः। ब्रह्म। अर्चत। वृत्रं। हनति। वृत्रऽहा। श

तऽक्रतुः। वज्रेण। शतऽपर्वणा। अभि। प्र। भर। धृषत। धृषत्ऽमनः। श्रवः। ते। चित्। असत्। बृहत्। अर्ष

न्तु। आपः। जवसा। वि। मातरः। हनः। वृत्रं। जयः। स्वः। रिति स्वः। यत्। जा। यथाः। अपूर्व्य। मघऽवन्। वृत्रऽह

वीं त्याय। तत्। पृथिवीं। अप्रथयः। तत्। अस्तभ्नाः। उत। द्यां। तत्। ते। यज्ञः। अजायत। तत्। अर्कः। उत। हस्कृतिः।

तत्। विश्वं। अभिऽभूः। असि। यत्। जातं। यत्। च। जन्त्वं। आमासु। पक्वं। ऐरयः। आ। सूर्यं। रोहयः। दिवि।

घर्मं। न। साम। तपत। सुवृक्तिऽभिः। जुष्टं। गिर्वणसे। बृहत्॥ ३२॥ आ। नः। विश्वासु। हव्यः। इन्द्रः। समत्ऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प.ब.

८२

82

सु।भूषन्तु।उप।अन्यानि।सवनानि।वृत्रऽहा।परमऽज्याः।ऋचीषमः।त्वं।दाता।प्रथमः।राधसां।असि

।असि।सत्यः।ईशानऽकृत्।तुविऽद्युम्नस्य।युज्या।आ।वृणीमहे।पुत्रस्य।शवसः।महः।प्र।स्तोमाः।ते।इन्द्र।

गिर्वणः।क्रियन्ते।अनतिऽअद्भुता।इमा।जुषस्व।हरिऽअश्व।योजना।इन्द्र।या।ते।अमन्महि।त्वं।हि।सत्यः।

मघऽवन्।अनानतः।वृत्रा।भूरि।निऽऋञ्जसे।सः।त्वं।शविष्ठ।वज्रऽहस्त।दाशुषे।।अर्वां

चं।रयिं।आ।कृधि।त्वं।इन्द्र।यशाः।असि।ऋजीषी।शवसः।पते।त्वं।वृत्राणि।हंसि।अप्रतीनि।ए

कः।इत्।अनुऽत्ता।चर्षणिऽधृता।तं।ऊं इति।त्वा।नूनं।असुर।प्रऽचेतसं।राधः।भागंऽइव।ईमहे।

महीऽइव।कृत्तिः।शरणा।ते।इन्द्र।प्र।ते।सुम्ना।नः।अश्नवन्।३।कन्या।वाः।अवऽयती।सोमं।अ ८२

© Dharmartha Trust J&K. Digitized by eGangotri

धानावंतंकरंभिणमपूपवंतमुक्थिनं।२

पि॰स्रुता।अविदत्।अस्तं।भरंती।अब्रवीत्।इंद्राय।सुनवै।त्वा।शक्राय।सुनवै।त्वा।असौ।यः।एषि।
वीरकः।गृहंऽगृहं।विऽचाकशत्।इमं।जंभऽसुतं।पिब।०।आ।चन।त्वा।चिकित्सामः।अधि।चन।त्वा।
न।इमसि।शनैःऽइव।शनकैःऽइव।इंद्राय।इंदो इति।परि।स्रव।कुवित्।शकत्।कुवित्।करत्।कु
वित्।नः।वस्यसः।करत्।कुवित्।पतिऽद्विषः।यतीः।इंद्रेण।संऽगमामहै।इमानि।त्रीणि।विष्टपा।
तानि।इंद्र।वि।रोहय।शिरः।ततस्य।उर्वरां।आत्।इदं।मे।उप।उदरे।असौ।च।या।नः।उर्वरा।आत्।
इमां।तन्वं।मम।अथो इति।ततस्य।यत्।शिरः।सर्वा।ता।रोमशा।कृधि।खे।रथस्य।खे।अनसः।
खे।युगस्य।शतक्रतो इति शतऽक्रतो।अपालां।इंद्र।त्रिः।पूत्वी।अकृणोः।सूर्यऽत्वचं।।२।।पातं।

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रमभिप्रगायत।

प॰घ॰ आ। वः। अंधसः। ०। विश्वऽसहाः। शतऽक्रतुं। मंहिष्ठं। चर्षणीनां। पुरुऽहूतं। पुरुऽस्तुतं। गाथान्यं। सऽ
८३ नः। नऽश्रुतं। इंद्रः। इति। ब्रवीतन। इंद्रः। इतं। महानां। दाता। वाजानां। नृतुः। महान्। अभिऽज्ञु। आ। यमत्।
अपात्। ऊं। इति। शिप्री। अंधसः। सुऽदक्षस्य। प्रऽहोषिणः। इंदोः। इंद्रः। यवऽआशिरः। ०। अर्चत। इंद्रं। तं म्वभिप्र
83 सोमस्य। पीतये। तत्। इत्। हि। अस्य। वर्द्धनं। १०। अस्य। पीत्वा। मदानां। देवः। देवस्य। ओजसा।
वृः। विश्वा। अभि। भुवना। भुवत्। ओं। इति। सत्राऽसहं। विश्वासु। गीर्षु। आऽयतं। आ। च्यवयसि।
ऊतये। युध्मं। संतं। अनर्वाणं। सोमऽपां। अनपऽच्युतं। नरं। अवार्यऽक्रतुं। शिक्षा। नः। इंद्र। रायः। आ
पुरु। विद्वान्। ऋचीषम। अव। नः। पार्ये। धने। अतः। चित्। इंद्र। नः। उप। आ। याहि। शतऽवाजया। ८३

© Dharmartha Trust J&K. Digitized by eGangotri

इषा। सहस्रऽवाजया॥९॥ अयाम। धीऽवतः। धियः। अर्वत्ऽभिः। शक्र। गोऽदरे। जयेम। पृत्ऽसु। वज्रिऽ
वः। वयं। ऊं इति। त्वा। शतक्रतो इति शतऽक्रतो। गावः। न। यवसेषु। आ। उक्थेषु। रणयामसि। विश्वाः। हि।
मर्त्यऽत्वना। अनुऽकामा। शतक्रतो इति शतऽक्रतो। अगन्म। वज्रिन्। आऽशसः। त्वे इति। सु। पुत्र। शव
सः। अवृत्रन्। कामऽकातयः। न। त्वां। इंद्र। अति। रिच्यते। सः। नः। वृषन्। सनिष्ठया। सं। घोरया। द्रवि
त्न्वा। धिया। अविड्ढि। पुरंऽध्या॥१०॥ यः। ते। नूनं। शतक्रतो इति शतऽक्रतो। इंद्र। द्युम्निऽतमः। मदः।
तेन। नूनं। मदे। मदेरिति मदेः। यः। ते। चित्रश्रवःऽतमः। यः। इंद्र। वृत्रहन्ऽतमः। यः। ओजःऽदातमः। म
दः। विद्म। हि। यः। ते। अद्रिऽवः। त्वाऽदत्तः। सत्य। सोमऽपाः। विश्वासु। दस्म। कृष्टिषु। इंद्राय। मद्वने। सुतं।

© Dharmartha Trust J&K. Digitized by eGangotri

२ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत। तमिद्वर्धंतु नो गिरः। आ त्वा विशंत्विंदवः

न त्वामिंद्राति रिच्यते २

प॰ष॰ परि। स्तोमं। तु। नः। गिरः। अर्कः। अर्चंतु। कारवः। यस्मिन्। विश्वाः। अधि। श्रियः। रणंति। सप्त। संऽ

८४ सदः। इंद्रं। सुते। हवामहे॥१॥ नाऽ समुद्रःऽइव। सिंधवः। विऽव्यक्। महिना। वृषन्। भक्षं। सोमस्य।

इंद्र। जागृवे। यः। इंद्र। जठरेषु। ते। अरं। ते। कुक्षयोः। सोमः। भवतु। वृत्रऽहन्। अरं। धामऽभ्यः। इंदवः। अ

रं। अश्वाय। गायति। श्रुतऽकक्षः। अरं। गवे। अरं। इंद्रस्य। धाम्ने। अरं। हि। स्म। सुतेषु। नः। सोमेषु।

इंद्र। भूषसि। अरं। ते। शक्र। दावने॥३॥ पराकात्तात्। चित्। अद्रिऽवः। त्वां। नक्षंत। नः। गिरः। अरं। ग

मामा। ते। वयं। एव। हि। असि। वीरऽयुः। एव। शूरः। उत। स्थिरः। एव। ते। राध्यं। मनः। एव। रातिः। तु

विऽमघ। विश्वेभिः। धायि। धातृऽभिः। अध। चित्। इंद्र। मे। सचा। मो इति। सु। ब्रह्माऽइव। तंद्रयुः। ८४

© Dharmartha Trust J&K. Digitized by eGangotri

भुवः।वाजानां।पते।मत्स्व।सुतस्य।गोऽमतः॥मा।नः।इंद्र।अभि।आऽदिशः।सूरः।अक्तुषु।आ।
यमन्।त्वा।युजा।वनेम।तत्।त्वया।इति।इंद्र।युजा।वयं।प्रति।ब्रुवीमहि।स्पृधः।त्वं।अस्माकं।
तव।स्मसि।त्वां।इत्।हि।त्वाऽयवः।अनुऽनोनुवतः।चरान्।सखायः।इंद्र।कारवः॥२०॥उत्।घ।
इत्।अभि।श्रुतऽमघं।वृषभं।नर्यऽअपसं।अस्तारं।एषि।सूर्य।नव।यः।नवतिं।पुरः।बिभेद।
बाहुऽओजसा।अहिं।च।वृत्रऽहा।अवधीत्॥सः।नः।इंद्रः।शिवः।सखा।अश्वऽवत्।गोऽमत्।य
वऽमत्।उरुऽधाराऽइव।दोहते॥यत्।अद्य।कत्।च।वृत्रऽहन्।उत्ऽअगाः।अभि।सूर्य।सर्वं।तत्।
इंद्र।ते।वशे।यत्।वा।प्रऽवृद्ध।सत्ऽपते।न।मरै।इति।मन्यसे।उतो इति।तत्।सत्यं।इत्।तव॥२१॥

© Dharmartha Trust J&K. Digitized by eGangotri

प.च. ये। सोमासः। पराऽवति। ये। अर्वाऽवति। सुन्विरे। सर्वान्। तान्। इन्द्र। गच्छसि। तं। इन्द्रं। वाजयामसि।
८५ महे। वृत्राय। हंतवे। सः। वृषा। वृषभः। भुवत्। इंद्रः। सः। दानमने। कृतः। ओजिष्ठः। सः। मदे। हितः।
द्युम्नी। श्लोकी। सः। सोम्यः। गिरा। वज्रः। न। संऽभृतः। सऽबलः। अनपऽच्युतः। ववक्षे। ऋष्वः। अ
85 स्तृतः। दुःऽगे। चित्। नः। सुऽगं। कृधि। गृणानः। इन्द्र। गिर्वणः। त्वं। च। मघऽवन्। वशः।। २२।। यस्य।
ते। नु। चित्। आऽदिशं। न। मिनंति। स्वऽराज्यं। न। देवः। न। अधिऽगुः। जनः। अध। ते। अप्रतिऽस्कुतं।
देवी इति। शुष्मं। सपर्यतः। उभे इति। सुऽशिप्र। रोदसी इति। त्वं। एतत्। अधारयः। कृष्णासु। रोहि
णीषु। च। परुष्णीषु। रुशत्। पयः। वि। यत्। अहेः। अध। त्विषः। विश्वे। देवासः। अक्रमुः। विदत्। ८५

© Dharmartha Trust J&K. Digitized by eGangotri

मृगस्य। अतनत्। अमः। आ। तत्। ऊं इति। मे। निःऽवरः। भुवत्। वृत्रऽहा। अदिष्ट। पौंस्यं। अजातऽशत्रुः। अस्तृ-
तः। श्रुतं। वः। वृत्रहन्ऽतमं। प्र। शर्धं। चर्षणीनां। आ। शुषे। राधसे। महे। अया। धिया। च। गव्यऽ-
या। पुरुऽनामन्। पुरुऽस्तुत। यत्। सोमेऽसोमे। आ। अभवः। बोधित्ऽमनाः। इत्। अस्तु। नः। वृत्रऽ-
हा। भूरिऽआसुतिः। शृणोतु। शक्रः। आऽशिषं। कया। त्वं। नः। ऊत्या। अभि। प्र। मंदसे। वृषन्। कया। स्तो-
तृऽभ्यः। आ। भर। कस्य। वृषा। सुते। सचा। निऽयुत्वान्। वृषभः। रणत्। वृत्रऽहा। सोमऽपीतये। २०॥
अभि। सु। नः। त्वं। रयिं। मंदसानः। सहस्रिणं। प्रऽयंता। बोधि। दाशुषे। पत्नीऽवंतः। सुताः। इमे।
उशंतः। यंति। वीतये। अपां। जग्मिः। निःऽचुंपुणः। इष्टाः। होत्राः। असृक्षत। इंद्रं। वृधासः। अध्वरे।

© Dharmartha Trust J&K. Digitized by eGangotri

इह्यास्य धमायाह्रीहिरण्यकेश्या। यदिंद्रम्ळयासिनः ।४
जोष्क्रामभिप्रयोहितं ।२
यदिंद्र॰। स्यामिद्धत्रहंतम ५

प॰ष॰ अछा। अवऽमृथं। ओजसा।ँ॰।तुभ्यं।सोमाः।सुताः। इमे। स्तीर्णं। बर्हिः। विभावसो इति विभाऽवसो।
२६ स्तोतऽभ्यः। इंद्रं। आ। वह॥२५॥ आ। ते। दक्षं। वि। रोचना। दधत्। रत्ना। वि। दाशुषे। स्तोतऽभ्यः। इंद्र।
अर्चत। आ। ते। दधामि। इंद्रियं। उक्था। विश्वा। शतक्रतो इति शतऽक्रतो। स्तोतऽभ्यः। इंद्र। मृळ
य। भद्रंऽभद्रं। नः। आ। भर। इषं। ऊर्जं। शतक्रतो इति शतऽक्रतो।ँ॰। सः। नः। विश्वानि। आ। भर। सु
86 वितानि। शतक्रतो इति शतऽक्रतो।ँ॰। सुतऽवंतः। हवामहे।ँ॰। (यदिंद्र) रधा। उपा। नः। हरिऽभिः। सुतं। याहि। म
उपनोहरि॰ दानां। पते।ँ॰। द्विता। यः। वृत्रऽहन्ऽतमः। विदे। इंद्रः। शतऽक्रतुः।ँ॰। (उप॰) त्वं। हि। वृत्रऽहन्। एषां। पाता।
सोमानां। असि।ँ॰। इंद्रः। इषे। ददातु। नः। ऋभुक्षणं। ऋभुं। रयिं। वाजी। ददातु। वाजिनं॥२७॥ ८६
उप॰

© Dharmartha Trust J&K. Digitized by eGangotri

तंसुनोविश्वेअर्यआसदागृणंतिकारवः।२

गोः। धयति। मरुतां। श्रवस्युः। माता। मघोनां। युक्ता। वह्निः। रथानां। यस्याः। देवाः। उपऽस्थे। व्रता।
विश्वे। धारयंते। सूर्यामासा। दृशे। कं। मरुतः। सोमऽपीतये। अस्ति। सोमः। अयं। सुतः। पिबंति।
अस्य। मरुतः। उत। स्वऽराजः। अश्विना। पिबंति। मित्रः। अर्यमा। तना। पूतस्य। वरुणः। त्रिऽसधस्थ
ॐ त्योन्वस्य स्य। जाऽवतः। जोषं। आ। इंद्रः। सुतस्य। गोऽमतः। प्रातः। होताऽइव। मत्सति॥२०॥ कत्। अति। त्विषंतः।
सूरयः। तिरः। आपःऽइव। स्रिधः। अर्षंति। पूतऽदक्षसः। कत्। वः। अद्य। महानां। देवानां। अवः। वृणे।
त्मना। च। दस्मऽवर्चसां। आ। ये। विश्वा। पार्थिवानि। पप्रथन्। रोचना। दिवः। मरुतः। सोमऽपीतये।
त्यान्। नु। पूतऽदक्षसः। दिवः। वः। मरुतः। हुवे। त्यान्। नु। ये। वि। रोदसी इति। तस्तभुः। मरुतः। हुवे।

अस्यसोमस्यपीतये।२

© Dharmartha Trust J&K. Digitized by eGangotri

अस्य　　　　　　　　　　　　　　　　अस्य

प.प. वो॑ऽ॥ यं। नु। मा। रु। तं॥ ग। णं। गि। रि। स्थां। वृ। ष। णं। हु। वे॥ र्ग। र॥ आ। त्वा। गि। रः। र। थीः। इ। व। अ। स्थुः। सु। ते। षु।
८७ गि। र्व। णः। अ। भि। त्वा। सां। अ। नू। ष। त। इं। द्र। [illegible] । व। त्सं। न। मा। त। रः। आ। त्वा। शु। क्राः। अ। चु। च्य। वुः। सु।
ता। सः। इं। द्र। गि। र्व। णः। पि। ब। तु। अ। स्य। अं। ध। सः। इं। द्र। वि। श्वा। सु। ते। हि। तं। पि। बा। सो। मं। म। दा। य। कं। इं। द्र। श्ये।
नः। आ। भृ। तं। सु। तं। त्वं। हि। श। श्व। ती। नां। प। तिः। रा। जा। वि। शां। अ। सि। शु। धि। ह। वं। ति। र। श्च्याः। इं। द्र। यः। त्वा।
स। प। र्य। ति। सुः। वी। र्य। स्य। गो। म। तः। रा। यः। पू। र्द्धि। म। हा। न्। अ। सि। इं। द्र। यः। ते। न। वी। य। सीं। गि। रं। मं। द्रां। अ।
जी। ज। न। त्। चि। कि। त्वि। तः। म। न। सं। धि। यं। प्र। त्नां। ऋ। त। स्य। पि। प्यु। षीं॥ ३॥ तं। ऊं। इ। ति। स्त। वा। म। यं। गि। रः।
इं। द्रं। उ। क्था। नि। वा। वृ। धुः। पु। रू। णि। अ। स्य। पौं। स्या। सि। सा। सं। तः। व। ना। म। हे॥ शु। द्धं। शु। द्धे। न। सा। म्ना। शु। द्धैः ८७

ऍ तो न्विंद्रं स्तवाम १

© Dharmartha Trust J&K. Digitized by eGangotri

उक्थैः। ववृध्वांसं। शुद्धः। आशीःऽवान्। ममत्तु। इंद्र। शुद्धः। नः। आ। गहि। शुद्धः। शुद्धाभिः। ऊतिऽभिः।
शुद्धः। रयिं। नि। धारय। शुद्धः। ममद्धि। सोम्य॥ इंद्र। शुद्धः। हि। नः। रयिं। शुद्धः। रत्नानि। दाशुषे। शुद्धः।
वृत्राणि। जिघ्नसे। शुद्धः। वाजं। सिसाससि॥ ३१॥ अस्मै। उषसः। आ। अतिरंत। यामं। इंद्राय। नक्तं।
ऊर्म्याः। सुऽवाचः। अस्मै। आपः। मातरः। सप्त। तस्थुः। नृऽभ्यः। तराय। सिंधवः। सुऽपाराः। अतिऽविद्धा।
विथुरेण। चित्। अस्त्रा। त्रिः। सप्त। सानु। संऽहिता। गिरीणां। न। तत्। देवः। न। मर्त्यः। तुतुर्यात्। या
नि। प्रऽवृद्धः। वृषभः। चकार। इंद्रस्य। वज्रः। आयसः। निऽमिश्लः। इंद्रस्य। बाह्वोः। भूयिष्ठं। ओजः।
शीर्षन्। इंद्रस्य। क्रतवः। निऽरेके। आसन्। आ। ईषंत। श्रुत्यै। उपाके। मन्ये। त्वा। यज्ञियं। यज्ञियानां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ मन्ये। त्वा। च्यवनं। अच्युतानां। मन्ये। त्वा। सत्वनां। इंद्र। केतुं। मन्ये। त्वा। वृषभं। चर्षणीनां। आ।
८८ यता। वज्रं। बाह्वोः। इंद्र। धत्स्व। मदऽच्युतं। अहये। हंतवै। ऊं इति। प्र। पर्वताः। अनवंत। प्र। गावः।
प्र। ब्रह्माणः। अभिऽनक्षंतः। इंद्रं॥ ३॥ तं। ऊं इति। स्तवाम। यः। इमा। जजान। विश्वा। जातानि।
88 अवराणि। अस्मात्। इंद्रेण। मित्रं। दिधिषेम। गीःऽभिः। उपो इति। नमःऽभिः। वृषभं। विशेम। वृ
त्रस्य। त्वा। श्वसथात्। ईषमाणाः। विश्वे। देवाः। अजहुः। ये। सखायः। मरुत्ऽभिः। इंद्र। सख्यं।
ते। अस्तु। अथ। इमाः। विश्वाः। पृतनाः। जयासि॥ त्रिः। षष्टिः। त्वा। मरुतः। ववृधानाः। उस्राःऽइ
वऽराशयः। यज्ञियासः। उप। त्वा। आ। इमः। कृधि। नः। भागऽधेयं। शुष्मं। ते। एना। हविषा॥ ८८

© Dharmartha Trust J&K. Digitized by eGangotri

विधेम। तिग्मं। आयुधं। मरुतां। अनीकं। कः। ते। इंद्र। प्रति। वज्रं। दधर्ष। अनायुधासः। असुराः।
अदेवाः। चक्रेण। तान्। अप। वप। ऋजीषिन्॥ महे। उग्राय। तवसे। सुऽवृक्तिं। प्र। ईरय। शिवऽत-
माय। पश्वः। गिर्वाहसे। गिरः। इंद्राय। पूर्वीः। धेहि। तन्वे। कुवित्। अंग। वेदत्॥ ३॥ उक्थऽवाहसे। ह
विऽभ्वे। मनीषां। द्रुणा। न। पारं। ईरय। नदीनां। नि। स्पृश। धिया। तन्वि। श्रुतस्य। जुष्टऽतरस्य। ०। कुविदंगवेद
तत्। विविड्ढि। यत्। ते। इंद्रः। जुजोषत्। स्तुहि। सुऽस्तुतिं। नमसा। आ। विवास। उप। भूष। जरितः। मा।
रुवण्यः। श्रवय। वाचं॥ कुवि अव। द्रप्सः। अंशुऽमतीं। अतिष्ठत्। इयानः। कृष्णः। दशऽभिः। सहस्रैः।
आवत्। तं। इंद्रः। शच्या। धमंतं। अप। स्नेहितीः। नृऽमनाः। अधत्त। द्रप्सं। अपश्यं। विषुणे। चरंतं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ उपऽह्वरे । नद्यः । अंशुऽमत्याः । नभः । न । कृष्णं । अवतस्थिऽवांसं । इष्यामि । वः । वृषणः । युध्यत ।
८९ आजौ । अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वं । तित्विषाणः । विशः । अदेवीः । अ-
भि । आऽचरंतीः । बृहस्पतिना । युजा । इंद्रः । ससहे ॥१४॥ [illegible] सप्तऽभ्यः । जायमानः । अश-
त्रुऽभ्यः । अभवः । शत्रुः । इंद्र । गूळ्हे इति । द्यावापृथिवी इति । अनु । अविंदः । विभुमत्ऽभ्यः । भुवने-
भ्यः । रणं । धाः ॥ अप्रतिऽमानं । ओजः । वज्रेण । वज्रिन् । धृषितः । जघंथ । त्वं । शुष्णस्य । अव ।
अतिरः । वधत्रैः । त्वं । गाः । इंद्र । शच्या । इत् । अविंदः ॥ त्वं । वृषभा । चर्षणीनां । घनः । वृत्राणां । तविषः ।
बभूथ । त्वं । सिंधून् । असृजः । तस्तभानान् । त्वं । अपः । अजयः । दासऽपत्नीः । स्वः । सुऽक्रतुः । र ८९

© Dharmartha Trust J&K. Digitized by eGangotri

सरत्रहैन्द्र:
सरत्रहैन्द्र

यएकृत्त

ऽमिता। यः। सुतेषु। अनुत्तऽमन्युः। यः। अहाऽइव। रेवान्। ०। नरि। अपांसि। कर्ता। सः। वृत्रऽहा। प्रति। इ
त्। अन्यं। आहुः। ०। चर्षणिऽधृता। तं। सुऽस्तुत्या। हव्यं। हुवेम। सः। प्रऽअविता। मघऽवा। नः। अधिऽव
क्ता। सः। वाजस्य। श्रवस्यस्य। दाता। ०। ऋभुक्षाः। सघः। जज्ञानः। हव्यः। बभूव। कृण्वन्। अपां
सि। नर्या। पुरूणि। सोमः। न। पीतः। हव्यः। सखिऽभ्यः। ३८। याः। इंद्र। भुजः। आ। अभरः। स्वः
ऽवान्। असुरेभ्यः। स्तोतारं। इंद्र। मघऽवन्। अस्य। वर्धय। ये। च। त्वे। इति। वृक्तऽबर्हिषः। यं। इंद्र
दधिषे। त्वं। अश्वं। गां। भागं। अव्ययं। यजमाने। सुन्वति। दक्षिणाऽवति। तस्मिन्। तं। धेहि। मा
पणौ। यः। इंद्र। सस्तिः। अव्रतः। अनुऽस्वापं। अदेवऽयुः। स्वैः। सः। एवैः। मुमुरत्। पोष्यं। रयिं। स

© Dharmartha Trust J&K. Digitized by eGangotri

यँ॑ अर्कासि परायति यदर्वावति वृत्रहन्।

५.५. नूतनः । धेहि । नः । ततनः ॥ अतः । त्वा । गीःऽभिः । द्युऽगत । इंद्र । केशिऽभिः । सुतऽवान् । आ । विवासति ।
१० यत् । वा । असि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि । यत् । पार्थिवे । सदने । वृत्रहन्ऽतम ।
यत् । अंतरिक्षे । आ । गहि ॥ सः । नः । सोमेषु । सोमऽपाः । सुतेषु । शवसः । पते । मादयस्व ।
90 राधसा । सूनृताऽवता । इंद्र । राया । परीणसा ॥ मा । नः । इंद्र । परा । वृणक् । भव । नः । सधऽमाद्यः ।
मानइंद्र· । त्वं । नः । ऊती । त्वं । इत् । नः । आप्यं ॥ अस्मे इति । इंद्र । सचा । सुते । नि । सद । पीतये । मधु । रुधि ।
अस्मेइंद्र जरित्रे । मघऽवन् । अवः । मत्यां ॥ न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिऽवः । विश्वा ।
नत्यादेवा· जातानि । शवसा । अभिऽभूः । असि ॥ विश्वाः । पृतनाः । अभिऽभूतरं । नरं । सऽजूः । ततक्षुः । १०

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रं।जज्ञनुः।च।राजसे।क्रत्वा।वरिष्ठं।वरे।आऽमुरिं।उत।उग्रं।ओजिष्ठं।तवसं।तरस्विनं॥३।सं
ईं।रेभासः।अस्वरन्।इंद्रं।सोमस्य।पीतये।स्वःऽपतिं।यत्।ईं।वृधे।धृतऽव्रतः।हि।ओजसा।सं।ऊ
तिऽभिः।नेमिं।नमंति।चक्षसा।मेषं।विप्राः।अभिऽस्वरा।सुऽदीतयः।वः।अद्रुहः।अपि।कर्णे।
तरस्विनः।सं।ऋक्वऽभिः।तं।इंद्रं।जोहवीमि।मघऽवानं।उग्रं।सत्रा।दधानं।अप्रतिऽस्कुतं।श
वांसि।मंहिष्ठः।गीःऽभिः।आ।च।यज्ञियः।ववर्तत्।राये।नः।विश्वा।सुऽपथा।कृणोतु।वज्री।
त्वं।पुरः।इंद्र।चिकित्।एना।वि।ओजसा।शविष्ठ।शक्र।नाशयध्यै।त्वत्।विश्वानि।भुवना
नि।वज्रिन्।द्यावा।रेजेते इति।पृथिवी इति।च।भीषा।तत्।मा।ऋतं।इंद्र।शूर।चित्र।पातु।अपः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.व. नावज्जिनरादुःउड्ता। अति।वर्षि।म्हरि।गं।विश्व।ःपन्ये स्वा।स्व।हूया।य्ये स्वा।रा।जन्।न्रा।।उन्।।इतिषष्ठ
७३ स्केषष्ठोध्यायः।। ।।ॐ म।।इंद्राय ह्लादशान्नमेध औह्मिहंस ऋम्युपांस्ये चकक्रुमोंसांम वर्ष्यो
पुरउह्मिहौ।त्वामिदाद्यौ।प्रागाथमयंने ह्लादशनि मो भार्गवः स्त्रैष्टुमं षष्ठीजगतीपरास्त्रिस्त्रै
९१ नुष्टुभोयमितिह्लचेनेंद्र आत्मानमस्तौदुपांस्येवा व्यारधकृषोकृशजमदग्निर्भार्गवोमेमा
वरूणंप्रागाथंत्रिस्त्रिष्टुबंतांस्तृतीयादिगायत्रीस्तो बृहतीस्तोत्रं राजस्व्वकं सपादादित्याश्वि
न्यौ।नायव्ये सो यौबृहत्सुष स्वा।सूर्यप्रभा स्तुति वीपाय मानीगव्येत्वम ग्नेह्यधिको भार्गवः
प्रयोगो बाहेस्पत्सो वाग्निः पावकः सहसस्सुत यो वा गन्यो गृहपतियविष्ठ यो वान्यतर आग्ने ७३

© Dharmartha Trust J&K. Digitized by eGangotri

यंत्वदर्शिषकू्ना।सोभरिबार्हतंपंचमीविराट्रूपा।सप्तम्याद्ययुजःसतोबृहत्योऽष्टम्यादियुजःक
कुबृहत्सीयसीककुबनुष्टुबंत्याग्निमारुतीनवमंमंउ ॐपावमानंसोम्यंस्वादिष्ठयादशमधु
छंदाःपवस्वमेधातिथिरेवभ्रुनःशेपःसनहिरण्यस्तुपःसामिद्धऽकादशीकाश्यपोऽसितोदेव
लोवाविंशतिःसूक्तान्याद्यमाप्रियश्चतुरनुष्टुबंतामंद्रयानवोसूत्रमेतेसोमाःपरिप्रियाप्र
स्वानासउपास्मैसोमाअसृग्रं॥ ॥हरिःॐ॥मा॥इंद्राय।साम।गायत।विप्राय।बृहते।बृहत्
धर्मऽकृते।विपःऽचिते।पनस्यवे।त्वं।इंद्र।अभिऽभूः।असि।त्वं।सूर्यं।अरोचयः।विश्वऽकर्मा।
विश्वऽदेवः।महान्।असि।विऽभ्राजन्।ज्योतिषा।स्वः।अगच्छः।रोचनं।दिवः।देवाः।ते।इंद्र।सख्या

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. य।येमिरे।आ।इंद्र।नः।गाधि।प्रियः।सत्राऽजित्वा।अगोह्यः।गिरिः।न।विश्वतः।पृथुः।पतिः।दिवः।अ
९२ भि।हि।सत्य।सोमऽपाः।उभेइति।बभूथ।रोदसीइति।इंद्र।असि।सुन्वतः।वृधः।पतिः।दिवः।०।
इंद्र।दर्ता।पुरां।असि।हंता।दस्योः।मनोः।वृधः।पतिः।दिवः।।३।।अध।हि।इंद्र।गिर्वणः।उप।त्वा।
92 ।कामान्।महः।ससृज्महे।उदाऽइव।यंतः।उदऽभिः।वाः।न।त्वा।यव्याभिः।वर्धति।शूर।ब्रह्माणि।
वावृध्वांसं।चित्।अद्रिऽवः।दिवेऽदिवे।युंजंति।हरी इति।इषिरस्य।गाथया।उरौ।रथे।उरुऽयुगा।
इंद्रऽवाहा।वचःऽयुजा।त्वं।नः।इंद्र।आ।भर।ऊर्जं।नृम्णं।शतक्रतोइति शतऽक्रतो।विऽचर्षणे।
।आ।वीरं।पृतनाऽसहं।त्वं।हि।नः।पिता।वसोइति।त्वं।माता।शतक्रतोइति शतऽक्रतो।बभूविथ। ९२

© Dharmartha Trust J&K. Digitized by eGangotri

अधा।ते।सुम्नं।ईमहे।त्वां।शुष्मिन्।पुरुऽहूत।वाजऽयंतः।उप।ब्रुवे।शतक्रतोइति।शतऽक्रतो।सः
नः।रास्व।सुऽवीर्यं॥२॥त्वां।इद्रा।हवेः।नरः।अपीव्यन्।वज्रिन्।भूर्णयः।सः।इंद्र।स्तोमऽवाह
सां।इह।श्रुधि।उप।स्वसरं।आ।गहि।मत्स्व।सुऽशिप्र।हरिऽवः।तत्।ईमहे।त्वेइति।आ।भूषं
ति।वेधसः।तव।श्रवांसि।उपऽमानि।उक्थ्या।सुतेषु।इंद्र।गिर्वणः।आयंतःऽइव।सूर्यं।विश्वा।
इत्।इंद्रस्य।भक्षत।वसूनि।जाते।जनमाने।ओजसा।प्रति।भागं।न।दीधिम।अनर्शऽरा
तिं।वसुऽदां।उप।स्तुहि।०।सः।अस्य।कामं।विधतः।न।रोषति।मनः।दानाय।चोदयन्।
त्वं।इंद्र।प्रऽनूर्तिषु।अभि।विश्वाः।असि।स्पृधः।अशस्तिऽहा।जनिता।विश्वऽतूः।असि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. त्वां। नूर्यं। तरुष्यन्तः। अनु। ते। शुष्मं। तुरयंतं। ईयतुः। क्षोणी इति। शिशुं। न। मातरा। विश्वाः। ते। स्पृ
९३ धः। श्नथयंत। मन्यवे। वृत्रं। यत्। इंद्र। तूर्वसि॥ इतः। ऊती। वः। अजरं। प्रऽहेतारं। अप्रऽहितं। आशुं।
जेतारं। हेतारं। रथिऽतमं। अतूर्तं। तुग्र्यऽवृधं॥ इष्कर्तारं। अनिःऽकृतं। सहःऽकृतं। शतंऽऊतिं। श
93 तऽक्रतुं। समानं। इंद्रं। अवसे। हवामहे। वसवानं। वसुऽजुवं॥ ३॥ अयं। ते। एमि। तन्वा। पुरस्तो
त्। विश्वे। देवाः। अभि। मा। यंति। पश्चात्। यदा। मह्यं। दीधरः। भागं। इंद्र। आत्। इत्। मया।
कृणवः। वीर्याणि॥ दधामि। ते। मधुनः। भक्षं। अग्रे। हितः। ते। भागः। सुतः। अस्तु। सोमः। अ
सः। च। त्वं। दक्षिणतः। सखा। मे। अध। वृत्राणि। जंघनाव। भूरि॥ प्र। सु। स्तोमं। भरत। वाजऽयंतः। ९३

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्राय। सत्यं। यदि। सत्यं। अस्ति। न। इंद्रः। अस्ति। इति। नेमः। ऊं इति। त्वः। आह। कः। ईं। ददर्श। कं। अभि।
स्तवाम। अयं। अस्मि। जरितरिति जरितः। पश्य। मा। इह। विश्वा। जातानि। अभि। अस्मि। मह्ना। ऋत
स्य। मा। प्रऽदिशः। वर्धयंति। आऽदर्दिरः। भुवना। दर्दरीमि। आ। यत्। मा। वेनाः। अरुहन्। ऋतस्य।
एकं। आसीनं। हर्यतस्य। पृष्ठे। मनः। चित्। मे। हृदः। आ। प्रति। अवोचत्। अचिक्रदन्। शिशुऽमंतः।
सखायः।०। या। चकर्थ। मघऽवन्। इंद्र। सुन्वते। पारावतं। यत्। पुरुऽसंभृतं। वसु। अपऽअवृणोः।
शरभाय। ऋषिऽबंधवे॥॥ प्र। नूनं। धावत। पृथक्। न। इह। यः। वः। अवावरीत्। नि। सीं। वृत्र
स्य। मर्मणि। वज्रं। इंद्रः। अपीपतत्। मनःऽजवाः। अयमानः। आयसीं। अतरत्। पुरं। दिवं। सुऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ प॰
९४ पर्णः। गत्वाय। सोमं। वज्रिणे। आ। अभरत्। समुद्रे। अंतरिति। शयते। उद्ना। वज्रः। अभिऽवृतः। भ
रंति। अस्मै। संऽयतः। पुरःऽप्रस्रवणाः। बलिं। यत्। वाक्। वदंती। अविऽचेतनानि। राष्ट्री। देवा
नां। निः। ससाद। मंद्रा। चतस्रः। ऊर्जं। दुदुहे। पयांसि। क्व। स्वित्। अस्याः। परमं। जगाम। देवीं।
95 वाचं। अजनयंत। देवाः। तां। विश्वऽरूपाः। पशवः। वदंति। सा। नः। मंद्रा। इषं। ऊर्जं। दुहाना। धेनुः।
वाक्। अस्मान्। उप। सुऽस्तुता। आ। एतु। ०। द्यौः। देहि। लोकं। वज्राय। विऽस्कभे। हनाव। वृत्रं।
रिणचाव। सिंधून्। इंद्रस्य। यंतु। प्रऽसवे। विऽसृष्टाः। ८। ऋधक्। इत्था। सः। मर्त्यः। शश
मे। देवऽतातये। यः। नूनं। मित्रावरुणौ। अभिष्टये। आऽचक्रे। हव्यऽदातये। वर्षिष्ठऽक्षत्रौ। उरुऽ ९४

ह् भि

© Dharmartha Trust J&K. Digitized by eGangotri

चक्षसा। नरा। राजाना। दीर्घश्रुत्ऽतमा। ता। बाहुता। न। दंसना। रथर्यतः। साकं। सूर्यस्य। रश्मि

ऽभिः। प्र। वः। मित्राय। वरुणाय। अविरः। दूतः। अद्रवत्। अयः। ऽशीर्षा। मदेऽरघुः। न। यः। संऽपृष्टे

ना। पुनः। हवीतवे। न। संऽवादाय। रमते। तस्मात्। नः। अद्य। संऽऋतेः। उरुष्यतं। बाहुऽभ्यां। नः। उ

रुष्यतं। प्र। मित्राय। प्र। अर्यम्णे। सचथ्यां। ऋतऽवसो। इत्यृतऽवसो। वरूथ्यं। वरुणे। छंद्यं। वचः। स्तो

त्रं। राजऽसु। गायत। ता। हि। नो। हिन्वेरा। अरुणं। ज्येन्यं। वसु। एकं। पुत्रं। तिसृणां। ता। धामानि। अमृताः

मर्त्यानां। अदब्धाः। अभि। चक्षते। आ। मे। वचांसि। उत्ऽयता। द्युमत्ऽतमानि। कर्त्वा। उभा। यातं

नासत्या। सऽजोषसा। प्रति। हव्यानि। वीतये। रातिं। यत्। वां। अरक्षसं। हवामहे। युवाभ्यां। वाजिनीव

सू।

© Dharmartha Trust J&K. Digitized by eGangotri

प.५. सू इति।वाजिनीऽवसू।प्राचीं।होत्रां।प्रऽतिरंतौ।इतं।नरा।गृणाना।आ।जमतुःऽअग्निना।आ।नः।
१५ यज्ञं।दिविऽस्पृशं।वायो इति।याहि।सुमन्मऽभिः।अंतरिति।पवित्रे।उपरि।श्रीणानः।अयं।शु
क्रः।अयामि।ते।ते इति।अध्वर्युः।पथिऽभिः।रजिष्ठैः।प्रति।हव्यानि।वीतये।अध।नियुत्वः।उभ
यस्य।नः।पिब।शुचिं।सोमं।गोऽआशिरं।७।बट्।महान्।असि।सूर्य।बट्।आदित्य।महा
95 न्।असि।महः।ते।सतः।महिमा।पनस्यते।अद्धा।देव।महान्।असि।बट्।सूर्य।श्रवसा।म
हान्।असि।सत्रा।देव।महान्।असि।मह्ना।देवानां।असुर्यः।पुरःऽहितः।विऽभु।ज्योतिः।अ
दाभ्यं।इयं।या।नीची।अर्किणी।रूपा।रोहिण्या।कृता।चित्राऽइव।प्रति।अदर्शि।आऽयती। १५

© Dharmartha Trust J&K. Digitized by eGangotri

अंलः । दृशाऽस्तु । बा ऋषु । प्रऽजाः । ह । तिस्रः । अतिऽआयं । ईयुः । नि । अन्याः । अर्कं । अभितः । विविश्रे ।
बृहत् । ह । तस्थौ । भुवनेषु । अंतरिति । पवमानः । हरितः । आ । विवेश । माता । रुद्राणां । दुहिता । व
सूनां । स्वसा । आदित्यानां । अमृतस्य । नाभिः । नाभिः । प्र । नु । वोचं । चिकितुषे । जनाय । मा । गां । अ
नागां । अदितिं । वधिष्ट । वचःऽविदं । वाचं । उत्ऽईरयंतीं । विश्वाभिः । धीभिः । उपऽतिष्ठमानां । देवीं ।
देवेभ्यः । परि । आऽईयुषीं । गां । आ । मा । अवृक्त । मर्त्यः । दभ्रऽचेताः ॥ ॥ त्वं । अग्ने । बृहत् । वयः । दधा
सि । देव । दाशुषे ॥ सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा । चिकित् । विभानो इति वि
ऽभानो । आ । वह ॥ चोदिष्ठेन । यविष्ठ्य । अभि । स्मः । वाजऽसातये । और्वभृगुऽवत् । शुचिं । अप्न

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.१. वानऽवत्। आ। जुह्वे। अग्निं। समुद्रऽवाससं। जुह्वे। वातऽस्वनं। कविं। पर्जन्यऽक्रंद्यं। सहः। ०। ७। आ।
९६ सवं। सवितुः। यथा। भगस्यऽइव। भुजिं। हुवे। ०अग्निं। वः। वृधंतं। अध्वराणां। पुरुऽतमं। अच्छ।
नप्त्रे। सहस्वते। अयं। यथा। नः। आऽभुवत्। त्वष्टा। रूपाऽइव। तक्ष्या। अस्य। क्रत्वा। यशस्वतः।
96 अयं। विश्वाः। अभि। श्रियः। अग्निः। देवेषु। पत्यते। आ। वाजैः। उप। नः। गमत्। विश्वेषां। इह। स्तुहि।
होतॄणां। यशःऽतमं। अग्निं। यज्ञेषु। पूर्व्यं॥ ३ आशीरं। पावकऽशोचिषं। ज्येष्ठः। यः। दमेषु। आ। दीदा
य। दीर्घश्रुत्ऽतमः। ०। गृणीहि। विप्र। शुष्मिणं। मित्रं। न। यातयत्ऽजनं। उप। वा। जा। मयः। गिरः। दे
दिशातीः। हविःऽकृतः। वायोः। अनीके। अस्थिरन्। यस्य। त्रिऽधातु। अवृतं। बर्हिः। तस्थौ। असंऽदि ९६

© Dharmartha Trust J&K. Digitized by eGangotri

नं।आपः।चित्।नि।दधा।पदं।पदं।देवस्य।मीळ्हुषः।अनाधृष्टाभिः।ऊतिऽभिः।भद्रा।सूर्यःऽइव।उपऽ
दृक्॥१२॥ अग्ने।घृतस्य।धीतिऽभिः।तेपानः।देव।शोचिषा॥ग॥ तं।त्वा।अजनंत।मातरः।कविं।दे
वासः।अंगिरः।हव्यऽवाहं।अमर्त्यं।प्रऽचेतसं।त्वा।कवे।अग्ने।दूतं।वरेण्यं।हव्यऽवाहं।नि।सेदिरे।
नहि।मे।अस्ति।अघ्न्या।न।स्वऽधितिः।वनन्ऽवति।अथ।एता।दृक्।भरामि।ते।यत्।अग्ने।का
नि।कानि।चित्।आ।ते।दारूणि।दध्मसि।ता।जुषस्व।यविष्ठ्य।यत्।अत्ति।उपऽजिह्विका।य
त्।वम्रः।अतिऽसर्पति।सर्वं।तत्।अस्तु।ते।घृतं।अग्निं।इंधानः।मनसा।धियं।सचेत।मर्त्यः।
अग्निं।ईधे।विवस्वऽभिः॥१२॥ अदर्शि।गातुवित्ऽतमः।यस्मिन्।व्रता।नि।आऽदधुः।उपो इति।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.प. सुजातं। आ। अर्यस्य। वृद्धं। अग्निं। नक्षंत। नः। गिरः। प्र। दैवः। दासः। अग्निः। देवान्। अच्छ। न। मज्मना।

२ अनु। मातरं। पृथिवीं। वि। वावृते। तस्थौ। नाकस्य। सानवि। यस्मात्। रेजंत। कृष्टयः। चर्कृत्यानि।

कृण्वतः। सहस्रऽसां। मेधसाताऽइव। त्मना। अग्निं। धीभिः। सपर्यत। प्र। यं। राये। निनीषसि।

97 मर्तः। यः। ते। वसो इति। दाशत्। सः। वीरं। धत्ते। अग्ने। उक्थऽशंसिनं। त्मना। सहस्रऽपोषिणं। सः।

दृळ्हे। चित्। अभि। तृणत्ति। वाजं। अर्वता। सः। धत्ते। अक्षिति। श्रवः। त्वे इति। देवऽत्रा। सदा। पुरु

वसो इति पुरुऽवसो। विश्वा। वामानि। धीमहि। ३। आ। यः। विश्वा। दयते। वसु। होता। मंद्रः। जना

नां। मधोः। न। पात्रा। प्रथमानि। अस्मै। प्र। स्तोमाः। यंति। अग्नये। अश्वं। न। गीःऽभिः। रथ्यं। सुऽदा १८

ना।

© Dharmartha Trust J&K. Digitized by eGangotri

नवः। मर्मृज्यंते। देवऽयवः। इमे इति। तोके इति। तनये। दस्म। विश्पते। पर्षि। राधः। मघोनां। प्र। मंहिष्ठा
य। गायत। ऋतऽवन्ने। बृहते। शुक्रऽशोचिषे। उपऽस्तुतासः। अग्नये। आ। वंसते। मघऽवा। वीरऽवत्।
यशः। समऽइद्धः। द्युम्नी। आऽहुतः। कुवित्। नः। अस्य। सुऽमतिः। नवीयसी। अच्छ। वाजेभिः। आऽगमत्
प्रेष्ठं। ऊं इति। प्रियाणां। स्तुहि। आऽसाव। अतिथिं। अग्निं। रथानां। यमं॥ ३४॥ उतऽइता। यः। निऽ
दिता। वेदिता। वसु। आ। यज्ञियः। ववर्तति। दुस्तरा। यस्य। प्रवणे। न। ऊर्मयः। धिया। वाजं। सिसा
सतः। मा। नः। हृणीतां। अतिथिः। वसुः। अग्निः। पुरुऽप्रशस्तः। एषः। यः। सुऽहोता। सुऽअध्वरः। मो
इति। ते। रिषन्। ये। अच्छोक्तिऽभिः। वसो इति। अग्ने। केभिः। चित्। एवैः। कीरिः। चित्। हि। त्वां। ईट्टे। दू

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प॰ स्यायाः। रातऽहव्यः। सुऽअध्वरः। आ। अग्ने। याहि। मरुत्ऽसखा। रुद्रेभिः। सोमऽपीतये। सोमऽर्याः। उ

९८ पऽस्तुः। स्तुतिं। मादयस्व। स्वःऽनरे॥३५॥ इत्यष्टमं मंडलं॥ स्वादिष्ठया। मदिष्ठया। पवस्व। सोम। धा

रया। इंद्राय। पातवे। सुतः। रक्षःऽहा। विश्वऽचर्षणिः। अभि। योनिं। अयःऽहतं। द्रुणा। सधऽस्थं। आ। अ

98 सदत्। वरिवःऽधातमः। भव। मंहिष्ठः। वृत्रहन्ऽतमः। पर्षि। राधः। मघोनां। अभि। अर्ष। महानां। दे

वानां। वीतिं। अंधसा। अभि। वाजं। उत। श्रवः। त्वां। अच्छ। चरामसि। तत्। इत्। अर्थं। दिवेऽदिवे। इंद्रो

इति। त्वेइति। नः। आऽशसः॥३६॥ पुनाति। ते। परिऽस्रुतं। सोमं। सूर्यस्य। दुहिता। वारेण। शश्वता।

तना। तं। ईं। अण्वीः। सऽमर्ये। आ। गृभ्णंति। योषणः। दश। स्वसारः। पार्ये। दिवि। तं। ईं। हिन्वंति। अ ९८

© Dharmartha Trust J&K. Digitized by eGangotri

ग्नुवः। धमंति। बाकुरं। दृतिं। त्रिऽधातु। वारणं। मधु। अभि। इमं। अघ्न्याः। उत। श्रीणंति। धेनवः। शिशुं।
सोमं। इंद्राय। पातवे। अस्य। इत्। इंद्रः। मदेषु। आ। विश्वा। वृत्राणि। जिघ्नते। शूरः। मघा। च। मंहते॥ ५॥
पवस्व। देवऽवीः। अति। पवित्रं। सोम। रंह्या। इंद्रं। इंदो इति। वृषा। आ। विश। आ। वच्यस्व। महि। प्सरः।
वृषा। इंदो इति। द्युम्नवत्ऽतमः। आ। योनिं। धर्णसिः। सदः। अधुक्षत। प्रियं। मधु। धाराः। सुतस्य। वेध
सः। अपः। वसिष्ट। सुऽक्रतुः। महांतं। त्वा। महीः। अनु। आपः। अर्षंति। सिंधवः। यत्। गोभिः। वासयि
ष्यसे। समुद्रः। अप्ऽसु। मामृजे। विष्टंभः। धरुणः। दिवः। सोमः। पवित्रे। अस्मऽयुः॥ ५॥ अचिक्रद
त्। वृषा। हरिः। महान्। मित्रः। न। दर्शतः। सं। सूर्येण। रोचते। गिरः। ते। इंदो इति। ओजसा। मर्मृज्यंते।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰
११
99

अपस्युवः। याभिः। मदाय। शुंभसे। तं। त्वा। मदाय। घृष्वये। ऊं इति। लोकऽकृत्नुं। ईमहे। तव। प्रऽशस्त
यः। महीः। अस्मभ्यं। इंदो इति। इंद्रऽयुः। मध्वः। पवस्व। धारया। पर्जन्यः। वृष्टिमान्ऽइव। गोऽसाः।
इंदो इति। नृऽसाः। असि। अश्वऽसाः। वाजऽसाः। उत। आत्मा। यज्ञस्य। पूर्व्यः॥ ३० ॥ एषः। देवः। अमर्त्यः
पर्णवीःऽइव। दीयति। अभि। द्रोणानि। आऽसदं। एषः। देवः। विपा। कृतः। अति। ह्वरांसि। धावति। पव
मानः। अदाभ्यः। एषः। देवः। विपन्युऽभिः। पवमानः। ऋतयुऽभिः। हरिः। वाजाय। मृज्यते। एषः। वि
श्वानि। वार्या। शूरः। यन्ऽइव। सत्वऽभिः। पवमानः। सिसासति। एषः। देवः। रथर्यति। पवमानः। दशस्य
ति। आविः। कृणोति। वग्वनुं॥ २० ॥ एषः। विप्रैः। अभिऽस्तुतः। अपः। देवः। वि। गाहते। दधत्। रत्नानि। ११

मा

© Dharmartha Trust J&K. Digitized by eGangotri

दाशुषे । एषः । दिवं । वि । धावति । तिरः । रजांसि । धारया । पवमानः । कनिक्रदत् । एषः । दिवं । वि । आ । अस
मा रत् । तिरः । रजांसि । अस्पृतः । पवमानः । सुऽअध्वरः । एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवि
त्रे । अर्षति । एषः । ऊं इति । स्यः । पुरुऽव्रतः । जज्ञानः । जनयन् । इषः । धारया । पवते । सुतः ॥ ३ ॥ सन । च । सोम । जे
षि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि । सन । ज्योतिः । सन । स्वः । विश्वा । च । सोम । सौभ
गा । ॰ । सन । दक्षं । उत । क्रतुं । अप । सोम । मृधः । जहि । ॰ । पवितारः । पुनीतन । सोमं । इंद्राय । पातवे । ॰ । त्वं । सू
र्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिऽभिः ॥ २ ॥ ॰ ज्योक् । पश्येम । सूर्यं । ॰ । अभि । अर्ष । सुऽआयुध ।
सोम । द्विऽबर्हसं । रयिं । ॰ । अभि । अर्ष । अनपऽच्युतः । रयिं । समत्ऽसु । ससहिः । ॰ । त्वां । यज्ञैः । अवीवृध

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प॰ न्।पवमाना।विऽधर्मणि।रयिं।नः।चित्रं।अश्विनं।इंदो इति।विश्वऽआयुं।आ।भर।।४।२३।।सम्ऽइद्धः।वि
३०० श्वतः।पतिः।पवमानः।वि।राजति।प्रीणन्।वृषा।कनिक्रदत्।तनूऽनपात्।पवमानः।शृंगे इति।शिशा मा
नः।अर्षति।अंतरिक्षेण।रारजत्।ईळेन्यः।पवमानः।रयिः।वि।राजति।द्युऽमान्।मधोः।धाराभिः।ओ
100 जसा।बर्हिः।प्राचीनं।ओजसा।पवमानः।स्तृणन्।हरिः।देवेषु।देवः।ईयते।उत्।आतैः।जिहते।बृहत्।
द्वारः।देवीः।हिरण्ययीः।पवमानेन।सुऽस्तुताः।।२४।।सुशिल्पे इति सुऽशिल्पे।बृहती इति।मही इति।
पवमानः।वृषण्यति।नक्तोषसा।न।दर्शने इति।उभा।देवा।नृऽचक्षसा।होतारा।दैव्या।हुवे।पवमा
नः।इंद्रः।वृषा।भारती।पवमानस्य।सरस्वती।इळा।मही।इमं।नः।यज्ञं।आ।गमन्।तिस्रः।देवीः। ३००

© Dharmartha Trust J&K. Digitized by eGangotri

सुऽपेशसः। वयरं। अग्रऽजां। गोपां। पुरःऽयावानं। आऽकुवे। इंदुः। इंद्रः। वृषा। हरिः। पवमानः। प्रजाऽपतिः। व
नस्पतिः। पवमानः। मध्वा। सं। अद्भिः। धारया। सहस्रऽवल्शं। हरितं। भ्राजमानं। हिरण्ययं। विश्वे। देवाः। स्वा
हाऽकृतिं। पवमानस्य। आ। गत। वायुः। बृहस्पतिः। सूर्यः। अग्निः। इंद्रः। सऽजोषसः। २५। मंद्रया। सोम।
धारया। वृषा। पवस्व। देवऽयुः। अव्यः। वारेषु। अस्मऽयुः। अभि। त्यं। मद्यं। मदं। इंदो इति। इंद्रः। इति। क्षर। अ
भि। वाजिनः। अर्वतः। अभि। त्यं। पूर्व्यं। मदं। सुवानः। अर्ष। पवित्रे। आ। अभि। वाजं। उत। श्रवः। अनु। द्रप्सा
सः। इंदवः। अपः। न। प्रऽवता। [illegible] असरन्। पुनानाः। इंद्रं। आशत। यं। अत्यंऽइव। वाजिनं। मृजंति। योष
णः। दश। वने। क्रीळंतं। अतिऽअविं। २६। तं। गोभिः। वृषणं। रसं। मदाय। देवऽवीतये। सुतं। भराय। सं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. सृजा।देवः।देवाय।धारया।इंद्राय।पवते।सुतः।पयः।यत्।अस्य।पीपयत्।आ।मा।यज्ञस्य।रंह्या।सुस्वा
३०१ नः।पवते।सुतः।प्रत्नं।नि।पाति।काव्यं।एव।पुनानः।इंद्रऽयुः।मदं।मदिष्ठ।वीतये।गुहा।चित्।दधिषे।गि
रः।२०।असृग्रं।इंदवः।पथा।धर्मन्।ऋतस्य।सुऽश्रियः।विदानाः।अस्य।योजनं।प्र।धारा।मध्वः।अ
(101) ग्रियः।महीः।अपः।वि।गाहते।हविः।हविष्षु।वंद्यः।प्र।युजः।वाचः।अग्रियः।वृषा।अव।चक्रदत्।वने।स
द्म।अभि।सत्यः।अध्वरः।परि।यत्।काव्या।कविः।नृम्णा।वसानः।अर्षति।स्वः।वाजी।सिसासति।
पवमानः।अभि।स्पृधः।विशः।राजाऽइव।सीदति।यत्।ईं।ऋण्वंति।वेधसः।२१।अव्यः।वारे।परि।
प्रियः।हरिः।वनेषु।सीदति।रेभः।वनुष्यते।मती।सः।वायुं।इंद्रं।अश्विना।साकं।मदेन।गच्छति।रणा।यः। १०१

© Dharmartha Trust J&K. Digitized by eGangotri

अस्य। धर्मऽभिः। आ। मित्रावरुणा। भगं। मध्वः। पवंते। ऊर्मयः। विदानाः। अस्य। शक्मऽभिः। अस्मभ्यं। रो

दसी इति। रयिं। मध्वः। वाजस्य। सातये। श्रवः। वसूनि। सं। जितं॥ २॥ एते। सोमाः। अभि। प्रियं। इंद्रस्य।

ना। कामं। अक्षरन्। वर्द्धंतः। अस्य। वीर्यं। पुनानासः। चमूऽसदः। गच्छंतः। वायुं। अश्विना। ते। नः। धांतु। सुऽवीर्यं। इं

ना। द्रस्य। सोम। राधसे। पुनानः। हार्दि। चोदय। ऋतस्य। योनिं। आऽसदं। मर्जंति। त्वा। दश। क्षिपः। हिन्वंति। स

प्ता। धीतयः। अनु। विप्राः। अमादिषुः। देवेभ्यः। त्वा। मदाय। कं। सृजानं। अति। मेष्यः। सं। गोभिः। वासया

मसि॥ ३॥ पुनानः। कलशेषु। आ। वस्त्राणि। अरुषः। हरिः। परि। गव्यानि। अव्यत। मघोनः। आ। पव

स्वा। नः। जहि। विश्वाः। अप। द्विषः। इंदो इति। सखायं। आ। विश। रयिं। दिवः। परि। स्ववा। द्युम्नं। पृथिव्याः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. अधि।स्नहः।नः।सोम।पृत्ऽस्तु।धाः।नृऽचक्षसं।त्वा।वयं।इन्द्रऽपीतं।स्वःऽविदं।भक्षी।महि।प्रऽजां।इषं॥३॥
१०२ परि।प्रिया।दिवः।कविः।वयांसि।नप्त्योः।हितः।सुवानः।याति।कविऽक्रतुः।प्रऽप्रा।क्षयाय।पन्यसे।जना
य।जुष्टः।अद्रुहा।वीती।अर्षा।चनिष्ठया।सः।सूनुः।मातरा।शुचिः।जातः।जाते इति।अरोचयत्।महान्।म
ही इति।ऋतऽवृधा।सः।सप्त।धीतिऽभिः।हितः।नद्यः।अजिन्वत्।अद्रुहः।याः।एकं।अक्षि।ववृधुः।ताः।अ
भि।सं।तं।अरत्नं।महे।युवानं।आ।दधुः।इंदुं।इन्द्र।तव।व्रते॥३॥अभि।वह्निः।अमर्त्यः।सप्त।पश्यति।
वावहिः।क्रिविः।देवीः।अतर्पयत्।अवा।कल्येषु।नः।पुमः।तमांसि।सोम।योध्या।तानि।पुनान।जंघ
नः।नु।नव्यसे।नवीयसे।सुऽउक्ताय।साधय।पथः।प्रत्नऽवत्।रोचय।रुचः।पवमान।महि।श्रवः। १०२

© Dharmartha Trust J&K. Digitized by eGangotri

गां । अश्वं । रासि । वीरऽवत् । सन । मेधां । सन । स्वः३इति स्वः ॥ ३३ ॥ प्र । स्वानासः । रथाःऽइव । अर्वंतः । न । श्र-
वस्यवः । सोमासः । राये । अक्रमुः ॥ हिन्वानासः । रथाःऽइव । दधन्विरे । गभस्त्योः । भरासः । कारिणांऽइव ।
राजानः । न । प्रशस्तिऽभिः । सोमासः । गोभिः । अंजते । यज्ञः । न । सप्त । धातृऽभिः । परि । सुवानासः । इंदवः ।
मदाय । बर्हणा । गिरा । सुताः । अर्षंति । धारया । आपानासः । विवस्वनः । जनंत । उषसः । भगं । सूराः । अ-
ण्वं । वि । तन्वते ॥ ३४ ॥ अप । द्वारा । मतीनां । प्रत्नाः । ऋण्वंति । कारवः । वृष्णः । हरसे । आयवः ॥ संऽईचीना-
सः । आसते । होतारः । सप्तऽजामयः । पदं । एकस्य । पिप्रतः ॥ नाभा । नाभिं । नः । आ । ददे । चक्षुः । चित् ।
सूर्ये । सचा । कवेः । अपत्यं । आ । दुहे । अभि । प्रिया । दिवः । पदं । अध्वर्युऽभिः । गुहा । हितं । सूरः । पश्य-

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. ति। चक्षसा॥ ३५॥ उप। अस्मै। गायत। नरः। पवमानाय। इंदवे। अभि। देवान्। इयक्षते। अभि। ते। म
१०३ धुना। पयः। अथर्वाणः। अशिश्रयुः। देवं। देवाय। देवयुः॥ सः। नः। पवस्व। शं। गवे। शं। जनाय। शं। अर्व
ते। शं। राजन्। ओषधीभ्यः। बभ्रवे। नु। स्वतवसे। अरुणाय। दिविस्पृशे। सोमाय। गाथं। अर्चत। ह
स्तच्युतेभिः। अद्रिभिः। सुतं। सोमं। पुनीतन। मधौ। आ। धावत। मधु॥ ३६॥ नमसा। इत्। उप। सीदत।
103 दध्ना। इत्। अभि। श्रीणीतन। इंदुं। इंद्रे। दधातन। अमित्रहा। विचर्षणिः। पवस्व। सोम। शं। गवे। देवे
भ्यः। अनुकामकृत्॥ इंद्राय। सोम। पातवे। मदाय। परि। सिच्यसे। मनश्चित्। मनसः। पतिः। पव
मान। सुवीर्यं। रयिं। सोम। रिरीहि। नः। इंदो। इति। इंद्रेण। नः। युजा॥ ३७॥ सोमाः। अस्रग्रं। इंद

© Dharmartha Trust J&K. Digitized by eGangotri

वः। सुताः। ऋतस्य। सदने। इंद्राय। मधुमत्ऽतमाः। अभि। विप्राः। अनूषत। गावः। वत्सं। न। मातरः। इंद्रं। सो
मस्य। पीतये। मदऽच्युत्। क्षेति। सदने। सिंधोः। ऊर्मा। विपःऽचित्। सोमः। गौरी इति। अधि। श्रितः। दिवः।
नाभा। विऽचक्षणः। अव्यः। वारे। महीयते। सोमः। यः। सुऽक्रतुः। कविः। यः। सोमः। कलशेषु। आ। अंतरिति।
पवित्रे। आऽहितः। तं। इंदुः। परि। सस्वजे॥ ५॥ प्र। वाचं। इंदुः। इष्यति। समुद्रस्य। अधि। विष्टपि। जिन्वन्।
कोशं। मधुऽश्चुतं॥ नित्यऽस्तोत्रः। वनस्पतिः। धीनां। अंतरिति। सबःऽदुघः। हिन्वानः। मानुषा। युगा।
अभि। प्रिया। दिवः। पदा। सोमः। हिन्वानः। अर्षति। विप्रस्य। धारया। कविः। आ। पवमान। धारय।
रयिं। सहस्रऽवर्चसं। अस्मे इति। इंदो इति। सुऽआभुवं॥ ९॥ इति षष्ठाष्टके सप्तमोध्यायः॥ ७॥ ७॥

© Dharmartha Trust J&K. Digitized by eGangotri

१.१. ।।हरिःऽॐम्।।सोमःपरिप्राष्टाविषधियाप्रतेप्रनिम्नेनेयपरिसुवानःसत्तयत्सोमप्रकविरेतेधा
१०४ यंस्यैतेसोमास्सःसोमाअस्रग्रंप्रसोमासःपवस्वषइंद्रदच्युतआगस्त्यस्तममदश्शंलेभ्मवाहोदार्द
च्युतंएषकविरमेधएषवाजीप्रियमेधःप्रास्यनरमेधःप्रधाराबिंदुःप्रसोमासोगोतमःप्रसो
104 मासःश्यावाश्वःपसोमासःस्त्रितःप्रसुवानआनःपवस्वप्रभुवसुरसाजिसस्तुतोरहूगणए
षउस्यआथुरर्षबृहन्मालिःपुनानःप्रेयगावोमेध्यातिथिर्जनयन्योअत्यइव।।ॐम्।।सोमः।
पुनानः।अर्षति।सहस्रऽधारः।अतिऽअविः।वायोः।इंद्रस्य।निःऽकृतं।पवमानं।अवस्यवः।विप्रं।
अभि।प्र।गायत।सुस्वानं।देवऽवीतये।पवंते।वाजऽसातये।सोमाः।सहस्रऽपाजसः।गृणानाः। १०४

© Dharmartha Trust J&K. Digitized by eGangotri

द्युवःऽपीतये।उत।नः।वाजऽसातये।पवस्व।बृहतीः।इषः।सुऽमत्।इंदो इति।सुऽवीर्यं।ते।नः।सहस्त्रिणं।
रयिं।पवंतां।आ।सुऽवीर्यं।सुवानाः।देवासः।इंदवः॥३॥अत्याः।हियानाः।न।हेतृऽभिः।असृग्रं।वाजऽसा
तये।वि।वारं।अव्यं।आशवः।वाश्राः।अर्षंति।इंदवः।अभि।वत्सं।न।धेनवः।दधन्विरे।गभस्त्योः।जुष्टः।
इंद्राय।मत्सरः।पवमान।कनिक्रदत्।विश्वाः।अप।द्विषः।अपऽघ्नन्।अराव्णः।पवमानाः।स्वःऽदृशः।यो जहि। ७
नौ।ऋतस्य।सीदत॥४॥परि।प्र।असिस्यदत्।कविः।सिंधोः।ऊर्मौ।अधि।श्रितः।कारं।बिभ्रत्।पुरुऽस्पृ
हं।गिरा।यदि।सऽबंधवः।पंच।व्राताः।अपस्यवः।परिऽकृण्वंति।धर्णसिं।आतू।अस्य।शुष्मिणः।रसे।
विश्वे।देवाः।अमत्सत।यदि।गोभिः।वसायते।निःऽरिणानः।वि।धावति।जहत्।शर्याणि।तान्वा।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. त्रे। संऽजिघ्नते। युजा। नप्तीभिः। यः। विवस्वतः। शुभ्रः। न। मम्रजे। युवा। गाः। कृण्वानः। न। निःऽनिजं।
३०५ ॥५॥ अति। श्रिती। तिरश्चता। गव्या। जिगाति। अण्व्या। वग्नुं। इयर्ति। यं। विदे। अभि। क्षिपः। सं। अग्म
ता। मर्जयन्तीः। इषः। पतिं। पृष्ठा। गृभ्णत। वाजिनः। परि। दिव्यानि। मर्मृशत्। विश्वानि। सोम। पार्थिवा।
105 वसूनि। याहि। अस्मऽयुः ॥८॥ एषः। धिया। याति। अण्व्या। शूरः। रथेभिः। आशुऽभिः। गच्छन्। इंद्रस्य।
निःऽकृतं। एषः। पुरु। धियाऽयते। बृहते। देवऽतातये। यत्र। अमृतासः। आसते। एषः। हितः। वि। नीयते।
अंतरिति। शुभ्रऽवता। पथा। यदि। तुंजंति। भूर्णयः। एषः। शृंगाणि। दोधुवत्। शिशीते। यूथ्यः। वृ
षा। नृम्णा। दधानः। ओजसा। एषः। रुक्मिऽभिः। ईयते। वाजी। शुभ्रेभिः। अंशुऽभिः। पतिः। सिंधूनां। ३०५

© Dharmartha Trust J&K. Digitized by eGangotri

भवन्त। एषः। वस्रनिः। पिब्दना। परुषा। ययिऽवान्। अति। अव्वारादेषु। गच्छति। एतं। मृजंति। मर्ज्यं। उप
पा। द्रोणेषु। आयवः। प्रऽचक्राणं। महीः। इषः। एतं। ऊं इति। त्यं। दश। क्षिपः। मृजंति। सप्त। धीतयः। सुऽ
आयुधं। मदिन्ऽतमं। पा। प्राते। सोतारः। ओण्योः। रसं। मदाय। घृष्वये। सर्गः। न। तक्ति। एतशः।
क्रत्वा। दक्षस्य। रथ्यं। अपः। वसानं। अंधसा। गोऽसां। अण्वेषु। सश्चिम। अनप्तं। अपूऽसु। दुस्तरं।
सोमं। पवित्रे। आ। सृज। पुनीहि। इंद्राय। पातवे। प्र। पुनानस्य। चेतसा। सोमः। पवित्रे। अर्षति। क्र
त्वा। सधऽस्थं। आ। असदत्। प्र। त्वा। नमःऽभिः। इंदवः। इंद्र। सोमाः। असृक्षत। महे। भराय। कारिणः।
पुनानः। रूपे। अव्यये। विश्वाः। अर्षन्। अभि। श्रियः। शूरः। न। गोषु। तिष्ठति। दिवः। न। सानु। पिप्युः

© Dharmartha Trust J&K. Digitized by eGangotri

प॰प॰ वी।धाराः।सुतस्य।वेधसः।रथाः।पवित्रे।अर्षति।त्वं।सोम।विपःऽचितं।तना।पुनानः।आयुषु।अव्यः।
१०६ वारं।वि।धावसि।द्याः।प्र।निम्नेनऽइव।सिंधवः।घ्नंतः।वृत्राणि।भूर्णयः।सोमाः।असृग्रं।आशवः।अ
भि।सुवानासः।इंद्रवः।वृष्टयः।पृथिवींऽइव।इंद्रं।सोमासः।अक्षरन्।अतिऽऊर्मिः।मत्सरः।मदः।सोमः।प
106 वित्रे।अर्षति।विघ्नन्।रक्षांसि।देवऽयुः।आ।कलशेषु।धावति।पवित्रे।परि।सिच्यते।उक्थैः।यज्ञेषु।व
र्द्धते।अति।त्री।सोम।रोचना।रोहन्।न।भ्राजसे।दिवं।इष्णन्।सूर्यं।न।चोदयः।अभि।विप्राः।अनू
षत।मूर्धन्।यज्ञस्य।कारवः।दधानाः।चक्षसि।प्रियं।तं।ऊं इति।त्वा।वाजिनं।नरः।धीभिः।विप्राः।अ
वस्यवः।मृजंति।देवऽतातये।मधोः।धाराः।अनु।क्षर।तीव्रः।सधऽस्थं।आ।असदः।चारुः।ऋताय। १०६

© Dharmartha Trust J&K. Digitized by eGangotri

पीतये॥ ३ आ । परि । सुवानः । गिरिऽस्थाः । पवित्रे । सोमः । अक्षारिति । मदेषु । सर्वऽधाः । असि । त्वं । विप्रः । त्वं । कविः ।
मधु । प्र । जातं । अंधसः ॥०॥ त्वं । विश्वे । सजोषसः । देवासः । पीतिं । आशत ॥०॥ आ । यः । विश्वानि । वार्या ।
वसूनि । हस्तयोः । दधे ॥०॥ यः । इमे इति । रोदसी इति । मही इति । सं । मातराऽइव । दोहते ॥०॥ परि । यः । रोदसी इ
ति । उभे इति । सद्यः । वाजेभिः । अर्षति ॥०॥ सः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् ॥०॥ यत्र । सोम । चि
त्रं । उक्थ्यं । दिव्यं । पार्थिवं । वसु । तत् । नः । पुनानः । आ । भर । युवं । हि । स्थः । स्वःपती इति स्वःऽपती । इंद्रः । च । सो
म । गोपती इति गोऽपती । ईशाना । पिप्यतं । धियः । वृषा । पुनानः । आयुषु । स्तनयन् । अधि । बर्हिषि । ह
रिः । सन् । योनिं । आ । असदत् । अवावशंत । धीतयः । वृषभस्य । अधि । रेतसि । सूनोः । वत्सस्य । मातरः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. कुवित्।वृषण्यंतीभ्यः।पुनानः।गर्भं।आऽदधत्।याः।शुक्रं।दुहते।पयः।उप।शिक्षा।अपऽतस्थुषः।भियसं।
३०७ आ।धेहि।शत्रुषु।पवमान।विदाः।रयिं।नि।शत्रोः।सोम।वृष्ण्यं।नि।शुष्मं।नि।वयः।तिर।दूरे।वा।स
तः।अंति।वा।॥१॥प्र।कविः।देवऽवीतये।अव्यः।वारेभिः।अर्षति।सह्वान्।विश्वाः।अभि।स्पृधः।सः।हि।
स्म।जरितृऽभ्यः।आ।वाजं।गोऽमंतं।इन्वति।पवमानः।सहस्रिणं।परि।विश्वानि।चेतसा।मृशसे।पव
से।मती।सः।नः।सोम।श्रवः।विदः।अभि।अर्ष।बृहत्।यशः।मघवत्ऽभ्यः।ध्रुवं।रयिं।इषं।स्तोतृऽभ्यः।
आ।भर।त्वं।राजाऽइव।सुऽव्रतः।गिरः।सोम।आ।विवेशिथ।पुनानः।वह्ने।अद्भुत।सः।वह्निः।अप्ऽसु।
दुस्तरः।मृज्यमानः।गभस्त्योः।सोमः।चमूषु।सीदति।क्रीळुः।मखः।न।मंहयुः।पवित्रं।सोम।गच्छसि। १०७

107

© Dharmartha Trust J&K. Digitized by eGangotri

दधन्वा । स्तोत्रे । सुऽवीर्यं ॥ १० ॥ एते । धावंति । इंदवः । सोमाः । इंद्राय । घृष्वयः । मत्सरासः । स्वःऽविदः । प्रऽवृण्वं

तः । अभिऽयुजः । सुऽस्वये । वरिवःऽविदः । स्वयं । स्तोत्रे । वयःऽकृतं । वृथा । क्रीळंतः । इंदवः । सधऽस्थं । अभि

एकं । इत् । सिंधोः । ऊर्मा । वि । अक्षरन् । एते । विश्वानि । वार्या । पवमानासः । आशत । हिताः । न । सप्तयः । र

थे । आ । अस्मिन् । पिशंगं । इंदवः । दधात । वेनं । आऽदिशे । यः । अस्मभ्यं । अरावा । ऋभुः । न । रथ्यं । नवं । दधा

त । केतं । आऽदिशे । शुक्राः । पवध्वं । अर्णसा । एते । ऊं इति । त्ये । अवीवृशन् । काष्ठां । वाजिनः । अकृत । सतः ।

प्र । असा । विष्णुः । मतिं ॥ ११ ॥ एते । सोमासः । आशवः । रथाःऽइव । प्र । वाजिनः । सर्गाः । सृष्टाः । अहेषत ।

एते । वाताःऽइव । उरवः । पर्जन्यस्यऽइव । वृष्टयः । अग्नेःऽइव । भ्रमाः । वृथा । एते । पूताः । विपःऽचितः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष. सोमासः।दधिऽआशिरः।विपा।वि।आनशुः।धियः।एते।मृष्टाः।अमर्त्याः।ससृऽवांसः।न।शश्रमुः
१०८ ।इयक्षंतः।पथः।रजः।एते।पृष्ठानि।रोदसोः।विऽप्रयंतः।वि।आनशुः।उत।इदं।उत्ऽतमं।रजः।तंतुं।
तन्वानं।उत्ऽतमं।अनु।प्रऽवतः।आशत।उत।इदं।उत्ऽतमाय्यं।त्वं।सोम।पणिऽभ्यः।आ।वसु।गव्या
108 नि।धारयः।ततं।तंतुं।अचिक्रदः।॥१२॥सोमाः।असृग्रं।आशवः।मधोः।मदस्य।धारया।अभि।वि
श्वानि।काव्या।अनु।प्रत्नासः।आयवः।पदं।नवीयः।अक्रमुः।रुचे।जनंत।सूर्यं।आ।पवमान।नः।
भर।अर्यः।अदाशुषः।गयं।कृधि।प्रजाऽवतीः।इषः।अभि।सोमासः।आयवः।पवंते।मद्यं।मदं।अ
भि।कोशं।मधुऽश्चुतं।सोमः।अर्षति।धर्णसिः।दधानः।इंद्रियं।रसं।सुऽवीरः।अभिशस्तिऽपाः।इं १०८

© Dharmartha Trust J&K. Digitized by eGangotri

द्राय। सोम। पवस्व। देवेभ्यः। सधऽमाद्यः। इंदो इति। वाजं। सिसाससि। अस्य। पीत्वा। मदानां। इंद्रः। वृत्राणि।
अप्रति। जघान। जघनत्। च। नु॥३॥१॥ प्र। सोमासः। अधन्विषुः। पवमानासः। इंदवः। श्रीणानाः। अप्ऽसु।
मृंजत। अभि। गावः। अधन्विषुः। आपः। न। प्रऽवता। यतीः। पुनानाः। इंद्रं। आशत। प्र। पवमान। धन्वसि। सो
म। इंद्राय। पातवे। नृऽभिः। यतः। वि। नीयसे। त्वं। सोम। नृऽमादनः। पवस्व। चर्षणिऽसहे। सस्निः। यः। अनुऽमा ८
द्यः। इंदो इति। यत्। अद्रिऽभिः। सुतः। पवित्रं। परि। धावसि। अरं। इंद्रस्य। धाम्ने। पवस्व। वृत्रहन्ऽतम। उक्थे
भिः। अनुऽमाद्यः। शुचिः। पावकः। अद्भुतः। शुचिः। पावकः। उच्यते। सोमः। सुतस्य। मध्वः। देवऽअवीः। अघ
शंसऽहा॥३॥४॥ पवस्व। दक्षऽसाधनः। देवेभ्यः। पीतये। हरे। मरुत्ऽभ्यः। वायवे। मदः। पवमान। धिया।

© Dharmartha Trust J&K. Digitized by eGangotri

१·४· हितः। अभि। योनिं। कनिक्रदत्। धर्मणा। वायुं। आ। विश। सं। देवैः। शोभते। वृषा। कविः। योनौ। अधि। प्रि
१०९ यः। वृत्रऽहा। देवऽवीतमः। विश्वा। रूपाणि। आऽविशन्। पुनानः। याति। हर्यतः। यत्र। अमृतासः। आसते।
अरुषः। जनयन्। गिरः। सोमः। पवते। आयुषक्। इंद्रं। गच्छन्। कविऽक्रतुः। आ। पवस्व। मदिन्ऽतम। पवि
109 त्रं। धारया। कवे। अर्कस्य। योनिं। आऽसदं। ॥४५॥ तं। अमृक्षंत। वाजिनं। उपऽस्थे। अदितेः। अधि। विप्रासः
। अण्व्या। धिया। तं। गावः। अभि। अनूषत। सहस्रऽधारं। अक्षितं। इंदुं। धर्त्तारं। आ। दिवः। तं। वेधां। मे
धया। अह्यन्। पवमानं। अधि। द्यवि। धर्णसिं। भूरिऽधायसं। तं। अह्यन्। भुरिजोः। धिया। संऽवसानं।
विवस्वतः। पतिं। वाचः। अदाभ्यं। तं। सानौ। अधि। जामयः। हरिं। हिन्वंति। अद्रिऽभिः। हर्यतं। भूरिऽचक्षसं। १०९

© Dharmartha Trust J&K. Digitized by eGangotri

तं।त्वा।हिन्वंति।वेधसः।पवमानं।गिराऽवृधं।इंदो।इति।इंद्राय।मत्सरं॥३८॥एषः।कविः।अभिऽस्तुतः।प
वित्रे।अधि।तोशते।पुनानः।घ्नन्।अप।स्रिधः।एषः।इंद्राय।वायवे।स्वःऽजित्।परि।सिच्यते।पवित्रे।दक्ष
ऽसाधनः।एषः।नृऽभिः।वि।नीयते।दिवः।मूर्द्धा।वृषा।सुतः।सोमः।वनेषु।विश्वऽवित्।एषः।गव्युः।अचिक्र
दत्।पवमानः।हिरण्यऽयुः।इंदुः।सत्राऽजित्।अस्तृतः।एषः।सूर्येण।हासते।पवमानः।अधि।द्यवि।पवि
त्रे।मत्सरः।मदः।एषः।शुष्मी।असिस्यदत्।अंतरिक्षे।वृषा।हरिः।पुनानः।इंदुः।इंद्रं।आ॥१७॥एषः।वा
जी।हितः।नृऽभिः।विश्वऽवित्।मनसः।पतिः।अव्यः।वारं।वि।धावति।एषः।पवित्रे।अक्षरत्।सोमः।
देवेभ्यः।सुतः।विश्वा।धामानि।आऽविशन्।एषः।देवः।शुभायते।अधि।योनौ।अमर्त्यः।वृत्रऽहा।दे

© Dharmartha Trust J&K. Digitized by eGangotri

प.ष.
३३०

110

वुऽवीतमः। एषः। वृषा। कनिक्रदत्। दशऽभिः। जामिऽभिः। यतः। अभि। द्रोणानि। धावति। एषः। सूर्यं। अरो
चयत्। पवमानः। विऽचर्षणिः। विश्वा। धामानि। विश्वऽवित्। एषः। शुष्मी। अदाभ्यः। सोमः। पुनानः। अर्षति।
देवऽअवीः। अघशंसऽहा॥३०॥ प्र। अस्य। धाराः। अक्षरन्। वृष्णः। सुतस्य। ओजसा। देवान्। अनु। प्रऽभूषतः।
सप्तिं। मृजंति। वेधसः। गृणंतः। कारवः। गिरा। ज्योतिः। जज्ञानं। उक्थ्यं। सुऽसहा। सोम। तानि। ते। पुनानाय।
प्रभुवसो इति प्रभुऽवसो। वर्द्धा। समुद्रं। उक्थ्यं। विश्वा। वसूनि। सं। जयन्। पवस्व। सोम। धारया। इनु। द्वेषां
सि। सध्र्यक्। रक्ष। सु। नः। अररुषः। स्वनात्। समस्य। कस्य। चित्। निदः। यत्र। मुमुच्महे। आ। इंदो इति।
पार्थिवा। रयिं। दिव्यं। पवस्व। धारया। द्युऽमंतं। शुष्मं। आ। भर॥१॥ प्र। धाराः। अस्य। शुष्मिणः। वृथा। ३३०

© Dharmartha Trust J&K. Digitized by eGangotri

पवित्रे। अक्षरन्। पुनानः। वाचं। इष्यति। इंदुः। हियानः। सोतृऽभिः। मृज्यमानः। कनिक्रदत्। इयर्ति। वग्नुं।
इंद्रियं। आ। नः। शुष्मं। नृऽसह्यं। वीरऽवंतं। पुरुऽस्पृहं। पवस्व। सोम। धारया। प्र। सोमः। अति। धार
या। पवमानः। असिस्यदत्। अभि। द्रोणानि। आऽसदं। अपःऽसु। त्वा। मधुमत्ऽतमं। हरिं। हिन्वंति। अद्रि
भिः। इंदो इति। इंद्राय। पीतये। सुनोत। मधुमत्ऽतमं। सोमं। इंद्राय। वज्रिणे। चारुं। शर्द्धाय। मत्सरं। २०॥
प्र। सोमाः। स्वःऽसुः। आऽध्यः। पवमानासः। अक्रमुः। रयिं। कृण्वंति। चेतनं। दिवः। पृथिव्याः। अधि। भव। इंदो इ
ति। द्युम्नऽवर्द्धनः। भव। वाजानां। पतिः। तुभ्यं। वाताः। अभिऽप्रियः। तुभ्यं। अर्षंति। सिंधवः। सोम। वर्द्ध
ति। ते। महः। तुभ्यं। गावः। घृतं। पयः। बभ्रो इति। दुदुह्रे। अक्षितं। वर्षिष्ठे। अधि। सानवि। सुऽआयुध

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ ष॰ स्यो। ते। सुतः। भुवनस्य। पते। वयं। इंदो इति। सखिऽत्वे। उरुष्मसि॥ २॥ आ। प्र। सोमासः। मदऽच्युतः। श्रव
३३३ सः। नः। मघोनः। सुताः। विदथे। अक्रमुः। आ। ईं। त्रितस्य। योषणः। हरिं। हिन्वंति। अद्रिऽभिः। इंदुं। इं
द्राय। पीतये। आ। ईं। हंसः। यथा। गणं। विश्वस्य। अवीवशत्। मतिं। अत्यः। न। गोभिः। अज्यते। उ
भे इति। सोम। अवऽचाकशत्। मृगः। न। तक्तः। अर्षसि। सीदन्। ऋतस्य। योनिं। अभि। गावः। अनूष आ।
त। योषा। जारंऽइव। प्रियं। अगन्। आजिं। यथा। हितं। अस्मे इति। धेहि। द्युऽमत्। यशः। मघवत्ऽभ्यः
च। मह्यं। च। सनिं। मेधां। उत। श्रवः॥ २२॥ प्र। सोमासः। विपःऽचितः। अपां। न। यंति। ऊर्मयः। वनानि।
महिषाःऽइव। अभि। द्रोणानि। बभ्रवः। शुक्राः। ऋतस्य। धारया। वाजं। गोऽमंतं। अक्षरन्। सुताः। इं ३३९

© Dharmartha Trust J&K. Digitized by eGangotri

द्राय।वायवे।वरुणाय।मरुत्ऽभ्यः।सोमाः।अर्षंति।विष्णवे।तिस्रः।वाचः।उत्।ईरते।गावः।मिमंति।धे
नवः।हरिः।एति।कनिक्रदत्।अभि।ब्रह्मीः।अनूषत।यह्वीः।ऋतस्य।मातरः।मर्मृज्यंते।दिवः।शिशुं।
रायः।समुद्रान्।चतुरः।अस्मभ्यं।सोम।विश्वतः।आ।पवस्व।सहस्रिणः।२३।प्र।सुवानः।धारया।
तना।इंदुः।हिन्वानः।अर्षति।रुजत्।दृळ्हा।वि।ओजसा।सुतः।इंद्राय।वायवे।वरुणाय।मरुत्ऽभ्यः।
सोमः।अर्षति।विष्णवे।वृषाणं।वृषऽभिः।यतं।सुन्वंति।सोमं।अद्रिऽभिः।दुहंति।शक्मना।पयः।भु
वत्।त्रितस्य।मर्ज्यः।भुवत्।इंद्राय।मत्सरः।सं।रूपैः।अज्यते।हरिः।अभि।ईं।ऋतस्य।विष्टपं।दुहते।
पृश्निऽमातरः।चारु।प्रियऽतमं।हविः।सं।[illegible]।एनं।अह्रुताः।इमाः।गिरः।अर्षंति।सऽस्रुतः।धेनूः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰घ॰ वाश्वाः। अचीक्रशत्॥२५॥ आ। नः। पवस्व। धारया। पवमान। रयिं। पृथुं। यया। ज्योतिः। विदासि। नः।
११२ इंद्रो इति। समुद्रंऽईङ्खय। पवस्व। विश्वंऽएजय। रायः। धर्त्ता। नः। ओजसा। त्वया। वीरेण। वीरऽवः।
अभि। स्याम। पृतन्यतः। क्षर। नः। अभि। वार्यं। प्र। वाजी। इंदुः। इष्यति। सिसासन्। वाजऽसाः। ऋषिः
112 व्रता। विदन्। नः। अयुधा। तेः। गोऽभिः। वाचंऽईङ्खयं। पुनानं। वासयामसि। सोमं। जनस्य। गोऽपतिं। वि
श्वेः। यस्य। व्रते। जनः। दाधार। धर्मणः। पतेः। पुनानस्य। प्रभुऽवसोः॥२५॥ असर्जि। रथ्यः। यथा। प
वित्रे। चम्वोः। सुतः। काष्र्मन्। वाजी। नि। अक्रमीत्। सः। वह्निः। सोम। जागृविः। पवस्व। देवऽवीः। अ
ति। अभि। कोशं। मधुऽश्चुतं। सः। नः। ज्योतींषि। पूर्व्या। पवमान। वि। रोचय। क्रत्वे। दक्षाय। नः। हिनु। ११२

© Dharmartha Trust J&K. Digitized by eGangotri

शुंभमानः। ऋतयुऽभिः। मृज्यमानः। गभस्त्योः। पवते। वारे। अव्यये। सः। विश्वा। दाशुषे। वसु। सोमः। दिव्या
नि। पार्थिवा। पर्वता। आ। अंतरिक्ष्या। आ। दिवः। पृष्ठं। अश्वऽयुः। गव्यऽयुः। सोम। रोहसि। वीरऽयुः। भव
सः। पते॥ २५॥ सः। सुतः। पीतये। वृषा। सोमः। पवित्रे। अर्षति। विऽघ्नन्। रक्षांसि। देवऽयुः। सः। पवित्रे। वि
ऽचक्षणः। हरिः। अर्षति। धर्णसिः। अभि। योनिं। कनिक्रदत्। सः। वाजी। रोचना। दिवः। पवमानः। वि। धाव
ति। रक्षःऽहा। वारं। अव्ययं। सः। त्रितस्य। अधि। सानवि। पवमानः। अरोचयत्। जामिऽभिः। सूर्यं। सह।
सः। वृत्रऽहा। वृषा। सुतः। वरिवःऽवित्। अदाभ्यः। सोमः। वाजंऽइव। असरत्। सः। देवः। कविना। इषितः।
अभि। द्रोणानि। धावति। इंदुः। इंद्राय। मंहना॥ २७॥ एषः। स्येः। ऊं इति। वृषा। रथः। अव्यः। वारेभिः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

९.१. षंति। गच्छन्। वाजी। सहस्रिणं। एतं। त्रितस्य। योषणः। हरिं। हिन्वंति। अद्रिऽभिः। इंदुं। इंद्राय। पीतये। एत
३३२ तं। त्यं। हरितः। दश। मर्मृज्यंते। अपस्युवः। याभिः। मदाय। शुंभते। एषः। स्यः। मानुषीषु। आ। श्येनः। न।
विक्षु। सीदति। गच्छन्। जारः। न। योषितं। एषः। स्यः। मद्यः। रसः। अव। चष्टे। दिवः। शिशुः। यः। इंदुः। वारं।
113 आ। अविशत्। एषः। स्यः। पीतये। सुतः। हरिः। अर्षति। धर्णसिः। क्रंदन्। योनिं। अभि। प्रियं। स्व। आ। अ
। अर्ष। बृहत्ऽमते। परि। प्रियेण। धाम्ना। यत्र। देवाः। इति। ब्रुवन्। परि। ऽरुण्वन्। अनिःऽरुतं। जनाय। या
तयन्। इषः। वृष्टिं। दिवः। परि। स्रव। सुतः। एति। पवित्रे। आ। त्विषिं। दधानः। ओजसा। विऽचक्षाणः। विर
रोचयन्। अयं। सः। यः। दिवः। परि। रघुऽयामा। पवित्रे। आ। सिंधोः। ऊर्मा। वि। अक्षरत्। आऽविवासन्। ३३२

पराऽवतः। अथो इति। अर्वाऽवतः। सुतः। इंद्राय। सिच्यते। मधु। संऽईचीनाः। अनूषत। हरिं। हिन्वंति। अद्रिऽभिः
। योनौ। ऋतस्य। सीदत॥ २॥ पुनानः। अक्रमीत्। अभि। विश्वाः। मृधः। विऽचर्षणिः। शुंभंति। विप्रं। धीतिऽभिः
। आ। योनिं। अरुणः। रुहत्। गमत्। इंद्रं। वृषा। सुतः। ध्रुवे। सदसि। सीदति। नु। नः। रयिं। महां। इंदो इति। अस्म
भ्यं। सोम। विश्वतः। आ। पवस्व। सहस्रिणं। विश्वा। सोम। पवमान। द्युम्नानि। इंदो इति। आ। भर। विदाः। सह
स्रिणीः। इषः। स्वः। नः। पुनानः। आ। भर। रयिं। स्तोत्रे। सुऽवीर्यं। जरितुः। वर्धय। गिरः। पुनानः। इंदो इति। आ।
भर। सोम। द्विऽबर्हसं। रयिं। वृषन्। इंदो इति। नः। उक्थ्यं॥ ३०॥ प्र। अये। गावः। न। भूर्णयः। त्वेषाः। अयासः।
अक्रमुः। घ्नंतः। कृष्णां। अप। त्वचं। सुवितस्य। मनामहे। अति। सेतुं। दुःऽआव्यं। सह्यां। सः। दस्युं। अव्रतं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ष॰ अण्वा । रंहेःऽइव । स्वनः । पवमानस्य । शुष्मिणः । चरंति । विऽद्युतः । दिवि । आ । पवस्व । महीं । इषं । गोऽमत् ।
३३४ इंदो इति । हिरण्यऽवत् । अश्वऽवत् । वाजऽवत् । सुतः । सः । पवस्व । विऽचर्षणे । आ । महि इति । रोदसी इति ।
पृण । उषाः । सूर्यः । न । रश्मिऽभिः । परि । नः । शर्मऽयंसा । धारया । सोम । विश्वतः । सर । रसाऽइव । विष्टपं ।
114 ॥ ३ ॥ आ । जनयन् । रोचना । दिवः । जनयन् । अप्ऽसु । सूर्यं । वसानः । गाः । अपः । हरिः । एषः । प्रत्नेन । मन्मना ।
देवः । देवेभ्यः । परि । धारया । पवते । सुतः । ववृधानाय । तूर्वये । पवंते । वाजऽसातये । सोमाः । सहस्रऽ
पाजसः । दुहानः । प्रत्नं । इत् । पयः । पवित्रे । परि । सिच्यते । क्रंदन् । देवान् । अजीजनत् । अभि । विश्वा
नि । वार्या । अभि । देवान् । ऋतऽवृधः । सोमः । पुनानः । अर्षति । गोऽमत् । नः । सोम । वीरऽवत् । अश्वऽवत् । ३३४

© Dharmartha Trust J&K. Digitized by eGangotri

प.प. वाजंऽवत् । सुतः । पवस्व । बृहतीः । इषः ॥ ३ ॥ यः । अत्यःऽइव । मृज्यते । गोभिः । मदाय । हरिऽवतः । तं । गीःऽभिः ।
३३५ वासयामसि । तं । नः । विश्वाः । अवस्युवः । गिरः । शुंभंति । पूर्वऽथा । इंदुं । इंद्राय । पीतये । पुनानः । याति । ह
115 र्यतः । सोमः । गीःऽभिः । परिऽकृतः । विप्रस्य । मेध्यः । अतिथिः । पवमान । विदाः । रयिं । अस्मभ्यं । सोम । सु
श्रियं । इंदो इति । सहस्रऽवर्चसं । इंदुः । अत्यः । न । वाजऽसृत् । कनिक्रंति । पवित्रे । आ । यत् । अक्षाः । अ
ति । देवऽयुः । पवस्व । वाजऽसातये । विप्रस्य । गृणतः । वृधे । सोम । रास्व । सुऽवीर्यं ॥ ३३ ॥ इति षष्ठाष्टके
अष्टमोध्यायः ॥ ॥ श्री ॥ ॥ छ ॥ ॥ छ ॥ छ ॥ छ ॥ छ ॥ छ ॥ छ ॥ छ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

पत्रसख्य
११५

१६७०

३

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रहस
११८

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ श्रीगणेशाय नमः ॥ हरिः ॐ ॥ महो नादश जगत्याष्टौ सप्त गुर्वैकं छमिंद्रं तु ष्टाव विकुंठा नाम सासुरींद्र
३ तुल्यं पुत्रमिच्छंती महन्नमः स्तेपे तस्यास्वयमेवेंद्रः पुत्रो जज्ञे स सप्तगुस्तु तिसंहृष्ट आत्मानमुत्तरैस्त्रिभि
स्तुष्टाव अहं भुवमेकादशांत्ये त्रिष्टुभौ सप्तमी चा अहं दामंत्यो पाद्ये च त्रिष्टुभौ प्र वो महे सप्त द्विजगत्साद्यंतं
केतेभिसारिण्यौ वषट्कारेण वृक्णेषु भ्रातृषु सोचीको ग्निरपः प्रविश्य देवैः समवददुत्तरैस्त्रिभिर्महान्न
यात्र यजुज्ञो ग्निर्वावयं विश्वे इत्युत्तरं च वषट् मन्युज्ञो देवानां यमे छामेत्युत्तरं चैकादशकं तद द्येति तु द्वयोर्गे
स्तेनु मा द्या जगत्यो ष्टमी चर्जेनां सुपट्दर्हदुक्थो वामदेव्यो दूरे ष्टा विदं ते सप्त वैश्वदेवं तु चतुर्थ्याद्या
स्तिस्रो अगस्त्यः पराणि चत्वारि सूक्तान्युक्ता ऋषयो द्वैपदेत्वत्रिमंडलेथ हे क्ष्वाको राजा समातिर्गोपा ३

© Dharmartha Trust J&K. Digitized by eGangotri

यनान्बंधवादीन्पुरोहितांस्त्यक्त्वान्यौमायाविनौश्रेष्ठतमौमत्वापुरोदधेतमिलरेऽकृद्धाअभिचेरुःरथतौमाया
विनौसुबंधोःप्राणानाचिक्षिपतुरथास्यभ्रातरस्त्वयोमाप्रगामेतिषट्कंगायत्रंस्वस्त्ययनंजपित्वायत्तइ
तिद्वादशर्चमानुष्टुभंमनआवर्तनंजेपुःप्रतारीतिदशर्चंचतस्रोनिर्ऋत्यपनोदार्थंजेपुश्चतुर्थ्यांसोमवा
स्तुवन्मृत्योरपगमायोत्तराभ्यांदैवीमसुनीतिंसप्तम्यांलिंगोक्तदेवताःशिष्टाभिःपंक्तिमहापंक्तिपंक्त्युत्तरा
भिर्द्यावापृथिव्योःसमिंद्रेतींद्रंचाद्यंचेनाऽजनमितिद्वादशर्चंआनुष्टुभंचतसृभिरसमातिमरस्तुवंस्त्वंच
म्येंद्रंवध्यागरस्त्यस्यस्वसामातैषांराजानमस्तौत्पराभिःसुबंधोर्जीवमाह्वयंस्तनमसमयालभंधसंन
मस्पृशन्पंचाद्यागायत्र्योऽष्टम्याद्येपंक्तीइदमित्थासमाधिकानामानेदिष्ठोमानवोवैश्वदेवंनतत्॥ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. ॐ म्। ॥ होता। जातः। महान्। नभःऽवित्। नृऽसद्मा। सीदत्। अपां। उपऽस्थे। दधिः। यः। धायि। सः। ते। वयांसि। यन्ता।
२ वसूनि। विधते। तनूऽपाः। पशुं। न। नष्टं। पदैः। अनु। ग्मन्। गुहा। चतंतं। उशिजः। नमःऽभिः। इच्छंतः। धीराः। भृगवः। इमं। विधंतो अपां सधस्थे
अविंदन्। इमं। त्रितः। भूरि। अविंदत्। इच्छन्। वैभूऽवसः। मूर्द्धनि। अघ्न्यायाः। सः। शेऽवृधः। जातः। आ। हर्म्येषु।
नाभिः। युवा। भवति। रोचनस्य। २॥ नमःऽभिः। प्रांचं। यज्ञं। नेतारं। अध्वराणां। विशां। अकृण्वन्। अरतिं। पाव मंद्रं होतारं उशिजो
2 कं। हव्यऽवाहं। दधतः। मानुषेषु। प्रऽभूः। जयंतं। महां। विपःऽधां। मूराः। अमूरं। पुरां। दर्माणं। नयंतः। गर्भं। व
नां। धियं। धुः। हिरिऽश्मश्रुं। न। अर्वाणं। धनऽअर्चं॥ ३॥ नि। पस्त्यासु। त्रितः। स्तभुऽयन्। परिऽवीतः। योनौ।
सीदत्। अंतरिति। अंतः। संऽगृभ्य। विशां। दमूनाः। विऽधर्मणा। अयंत्रैः। ईयते। नॄन्। अस्य। अजरासः। दमां। २

© Dharmartha Trust J&K. Digitized by eGangotri

अरित्राः । अर्चत्ऽधूमासः । अग्नयः । पावकाः । श्वितीचयः । श्वात्रासः । भुरण्यवः । वनऽसदः । वायवः । न । सोमाः ।
प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः । तं । आयवः । शुचयंतं । पावकं । मंद्रं । होतारं । दधिरे ।
यजिष्ठं । द्यावा । यं । अग्निं । पृथिवी इति । जनिष्टां । आपः । त्वष्टा । भृगवः । यं । सहःऽभिः । ईळेन्यं । प्रथमं । मातरिश्वा ।
देवाः । ततक्षुः । मनवे । यजत्रं । यं । त्वा । देवाः । दधिरे । हव्यऽवाहं । पुरुऽस्पृहः । मानुषासः । यजत्रं । यामन् । अग्ने ।
स्तुवते । वयः । धाः । प्र । देवऽयन् । यशसः । सं । हि । पूर्वीः ॥ २ ॥ जगृभ्म । ते । दक्षिणं । इंद्र । हस्तं । वसुऽयवः । वसुऽपते ।
वसूनां । विद्म । हि । त्वा । गोऽपतिं । शूर । गोनां । अस्मभ्यं । चित्रं । वृषणं । रयिं । दाः । सुऽआयुधं । सुऽअवसं । सुऽनी
थं । चतुःऽसमुद्रं । धरुणं । रयीणां । चर्कृत्यं । शंस्यं । भूरिऽवारं । ० । सुऽब्रह्माणं । देवऽवंतं । बृहंतं । उरुं । गभीरं ।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ.अ. पृथुऽबुध्नं। इंद्र। श्रुतऽऋषिं। उग्रं। अभिमातिऽसहं॥०॥ सनत्ऽवाजं। विप्रऽवीरं। तरुत्रं। धनऽस्पृतं। शूशुऽवांसं। सुऽ
३ दक्षं। दस्युऽहनं। पूःऽभिदं। इंद्र। सत्यं॥०॥ अश्वऽवंतं। रथिनं। वीरऽवंतं। सहस्रिणं। शतिनं। वाजं। इंद्र। भद्रऽव्रातं।
विप्रऽवीरं। स्वःऽसां॥०॥३॥ प्र। सप्तऽगुं। ऋतऽधीतिं। सुऽमेधां। बृहस्पतिं। मतिः। अच्छ। जिगाति। यः। आंगिरसः।
नमसा। उपऽसद्यः॥०॥ वनीवानः। मम। दूतासः। इंद्रं। स्तोमाः। चरंति। सुऽमतीः। इयानाः। हृदिऽस्पृशः। मनसा। व
च्यमानाः॥०॥ यत्। त्वा। यामि। दद्धि। तत्। नः। इंद्र। बृहंतं। क्षयं। असमं। जनानां। अभि। तत्। द्यावापृथिवी इति।
गृणीतां॥०॥४॥ अहं। भुवं। वसुनः। पूर्व्यः। पतिः। अहं। धनानि। सं। जयामि। शश्वतः। मां। हवंते। पितरं। न। जं
तवः। अहं। दाशुषे। वि। भजामि। भोजनं। अहं। इंद्रः। रोधः। वक्षः। अथर्वणः। त्रिताय। गाः। अजनयं। अहेः। अ ३

© Dharmartha Trust J&K. Digitized by eGangotri

धि। अहं। दस्युऽभ्यः। परि। नृम्णं। आ। ददे। गोत्रा। शिक्षन्। दधीचे। मातरिश्वने। मह्यं। त्वष्टा। वज्रं। अतक्षत्। आ।
यसं। मयि। देवासः। अवृजन्। अपि। क्रतुं। मम। अनीकं। सूर्यस्यऽइव। दुस्तरं। मां। आर्यंति। कृतेन। कर्त्वेन।
च। अहं। एतं। गव्ययं। अश्व्यं। पशुं। पुरीषिणं। सायकेन। हिरण्ययं। पुरु। सहस्रा। नि। शिशामि। दाशुषे। यत्।
मा। सोमासः। उक्थिनः। अमंदिषुः। अहं। इंद्रः। न। परा। जिग्ये। इत्। धनं। न। मृत्यवे। अव। तस्थे। कदा। चन। सोमं।
इत्। मा। सुन्वंतः। याचत। वसु। न। मे। पूरवः। सख्ये। रिषाथन। ५॥ अहं। एतान्। शाश्वसतः। द्वाऽद्वा। इंद्रं। ये। व
ज्रं। युधये। अकृण्वत। आऽह्वयमानान्। अव। हन्मना। अहनं। दृळ्हा। वदन्। अनमस्युः। नमस्विनः। अभि।
इदं। एकं। एकः। अस्मि। निष्षाट्। अभि। द्वा। किं। ऊं इति। त्रयः। करंति। खले। न। पर्षान्। प्रति। हन्मि। भूरि। किं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ मा।निंदत।शत्रवः।आ।मिंद्राः॥अहं।गुंगुऽभ्यः।अतिथिऽग्वं।इष्करं।इषं।न।वृत्रऽतुरं।विक्षु।धारयं।यत्।प
४ र्णयऽघ्ने।उत।वा।करंजऽहा।प्र।अहं।महे।वृत्रऽहत्ये।अशुश्रवि।प्र।मे।नमी।साप्यः।इषे।भुजे।भूत्।गवां।
एषे।सख्या।कृणुत।द्विता।दिद्युं।यत्।अस्य।समत्ऽइषु।मंहयं।आ।त्।इत्।एनं।शंस्यं।उक्थ्यं।करं।प्र।ने
मस्मिन्।ददृशे।सोमः।अंतः।गोपाः।नेमं।आविः।अस्थाः।कृणोति।सः।तिग्मऽशृंगं।वृषभं।युयुत्सन्।
द्रुहः।तस्थौ।बहुले।बद्धः।अंतरिति।आदित्यानां।वसूनां।रुद्रियाणां।देवः।देवानां।न।मिनामि।धाम।
ते।मा।भद्राय।शवसे।ततक्षुः।अपराऽजितं।अस्तृतं।अषाळ्हं॥ ५॥अहं।दां।गृणते।पूर्व्यं।वसु।अहं।
ब्रह्म।कृणवं।मह्यं।वर्धनं।अहं।भुवं।यजमानस्य।चोदिता।अयज्वनः।साक्षि।विश्वस्मिन्।भरे।मां। ४

© Dharmartha Trust J&K. Digitized by eGangotri

पुरः। इंद्रं। नाम। देवऽता। दिवः। च। ग्मः। च। अपां। च। जंतवः। अहं। हरी इति। वृषणा। विऽव्रता। रघू इति। अहं। वज्रं। शव

सा। धृष्णु। आ। ददे। अहं। अत्कं। कवये। शिश्नथं। हथैः। अहं। कुत्सं। आवं। आभिः। ऊतिऽभिः। अहं। शुष्णस्य। श्नथि

ता। वधः। यमं। न। यः। ररे। आर्यं। नाम। दस्यवे। अहं। पिताऽइव। वेतसून्। अभिष्टये। तुग्रं। कुत्साय। स्मदिभं।

च। रंधयं। ०। राजानि। प्रऽयतः। भरे। तुजये। न। प्रियाः। आऽधृषे। अहं। रंधयं। मृगयं। श्रुतर्वणे। यत्। मा। अजिहीत। अहं भुवं यन्ने मानस्य।

अ वयुना। च। न। आनुषक्। अहं। वेशं। नम्रं। आयवे। अकरं। अहं। सव्याय। पट्ऽगृभिं। अरंधयं। ७। अहं। सः। यः। न

वऽवास्त्वं। बृहत्ऽरथं। सं। वृत्राऽइव। दासं। वृत्रऽहा। अरुजं। यत्। वर्धयंतं। प्रथयंतं। आनुषक्। दूरे। पारे। रजसः।

रोचना। अकरं। अहं। सूर्यस्य। परि। यामि। आशुऽभिः। प्र। एतशेभिः। वहमानः। ओजसा। यत्। मा। सावः। मनुः

© Dharmartha Trust J&K. Digitized by eGangotri

१·मु· षः। आ। हा। निःऽनिजे। कः। परऽस्था। रुषा। दासं। कृण्वा। हये। अहं। सत्रुऽहा। न। कुरषः। न। ऊःऽत्वरः। प्र। अश्वं। वयं। शवसा।
५ तुर्वशं। यदुं। अहं। नि। अन्यं। सहसा। सहः। करं। न। वंऽत्रा पतः। न। गृतिं। च। वक्षयं। अहं। सप्त। स्रवतः। धारयं।
वृषा। द्रवित्वः। पृथिव्यां। सीराः। अधि। अहं। अर्णांसि। वि। तिरामि। सुऽक्रतुः। युधा। विदं। मनवे। गातुं।
इष्टये। अहं। तत्। आसु। धारयं। यत्। आसु। न। देवः। चन। त्वष्टा। अधारयत्। रुशत्। स्पार्हं। गवां। ऊधःऽसु। वक्ष य
णासु। आ। मधोः। मधु। श्वात्र्यं। सोमं। आऽशिरं। एव। देवान्। इंद्रः। विव्याय। नृऽत्रा। प्र। च्यौत्नेन। मघऽवा। स
विश्वे ता ते स्तऽराधाः। १०। हरिऽवः। शचीऽवः। अभि। नु। सतः। स्वऽयशाः। गृणंति। सूनु। मंदमानाय। अंधसः। अर्चा। विश्वा घवो म॒हे
नराय। विश्वऽसुवे। इंद्रस्य। वस्यः। सुऽमत्वं। सहः। महि। श्रवः। नृम्णं। च। रोदसी इति। सपर्यतः। सः। चित्। नु। ५

© Dharmartha Trust J&K. Digitized by eGangotri

सख्या। नर्यः। इनः। स्तुतः। चर्कृत्यः। इन्द्रः। माऽवते। नरे। विश्वासु। धूःऽसु। वाजऽकृत्येषु। सत्ऽपते। वृत्रे। वा। अ
प्ऽसु। अभि। शूर। मंदसे। के। ते। नरः। इंद्र। ये। ते। इषे। ये। ते। सुम्नं। सऽधन्यं। इयक्षान्। के। ते। वाजाय। असुर्या
य। हिन्विरे। के। अप्ऽसु। स्वासु। उर्वरासु। पौंस्ये। भुवः। त्वं। इंद्र। ब्रह्मणा। महान्। भुवः। विश्वेषु। सवनेषु।
यज्ञियः। भुवः। नृन्। च्यौत्नः। विश्वस्मिन्। भरे। ज्येष्ठः। च। मंत्रः। विश्वऽचर्षणे। अव। नु। कं। ज्यायान्। यज्ञऽव
नसः। महीं। ते। ओमात्रां। कृष्टयः। विदुः। असः। नु। कं। अजरः। वर्धाः। च। विश्वा। इत्। एता। सवना। तूतुमा।
कृषे। एता। विश्वा। सवना। तूतुमा। कृषे। स्वयं। सूनो इति। सहसः। यानि। दधिषे। वराय। ते। पात्रं। धर्मणे।
तना। यज्ञः। मंत्रः। ब्रह्म। उत्ऽयतं। वचः। ये। ते। विप्र। ब्रह्मऽकृतः। सुते। सचा। वसूनां। च। वसुनः। च। दावने।

© Dharmartha Trust J&K. Digitized by eGangotri

१·अ· प्रा । ते । सुम्नस्य । मनसा । पथा । भुवेम । मदे । सुतस्य । सोम्यस्य । अंधसः ॥ ७ ॥ महत् । तत् । उल्बं । स्थविरं । तत् ।
५ आसीत् । येन । आऽविष्टितः । प्रऽविवेथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । शि
एकः ॥ कः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिऽअपश्यत् । क्वं । अह । मित्रावरुणा । क्षियंति ।
6 अग्नेः । विश्वाः । संऽइधः । देवऽयानीः ॥ ऐच्छाम । त्वा । बहुधा । जातऽवेदः । प्रऽविष्टं । अग्ने । अपऽसु । ओषधीषु ।
तं । त्वा । यमः । अचिकेत् । चित्रभानो इति चित्रऽभानो । दशऽअंतरुष्यात् । अतिऽरोचमानं ॥ होत्रात् । अहं । वरु ल
ण । बिभ्यत् । आयं । न । इत् । एव । मा । युनजन् । अत्र । देवाः । तस्य । मे । तन्वः । बहुधा । निऽविष्टाः । एतं । अर्थं ।
न । चिकेत । अहं । अग्निः ॥ आ । इहि । मनुः । देवऽयुः । यज्ञऽकामः । अरंऽकृत्य । तमसि । क्षेषि । अग्ने । सुऽगान् । ५

© Dharmartha Trust J&K. Digitized by eGangotri

पथः। कृणुहि। देवऽयानान्। वह। हव्यानि। सुऽमनस्यमानः॥ ३॥ अग्नेः। पूर्वे। भ्रातरः। अर्थं। एतं। रथीऽइव। अध्वा

नं। अनु। आ। अवरीवुरिति। तस्मात्। भिया। वरुण। दूरं। आयं। गौरः। न। क्षेप्नोः। अविजे। ज्यायाः। कुर्मः। ते। आयुः।

अजरं। यत्। अग्ने। यथा। युक्तः। जातऽवेदः। न। रिष्याः। अथ। वहासि। सुऽमनस्यमानः। भागं। देवेभ्यः। हविषः।

सुऽजात। प्रऽयाजान्। मे। अनुऽयाजान्। च। केवलान्। ऊर्जस्वन्तं। हविषः। दत्त। भागं। घृतं। च। अपां। पुरुषं। च। ओ

षधीनां। अग्नेः। च। दीर्घं। आयुः। अस्तु। देवाः। तव। प्रऽयाजाः। अनुऽयाजाः। च। केवले। ऊर्जस्वन्तः। हविषः। सन्तु। भा

गाः। तव। अग्ने। यज्ञः। अयं। अस्तु। सर्वः। तुभ्यं। नमन्तां। प्रऽदिशः। चतस्रः॥ २२॥ विश्वे। देवाः। शास्तन। मा। यथा।

इह। होता। वृतः। मनवै। यत्। निऽसद्य। प्र। मे। ब्रूत। भागऽधेयं। यथा। वः। येन। पथा। हव्यं। आ। वः। वहानि। अहं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ होता। नि। असीदत्। यजीयान्। विश्वे। देवाः। मरुतः। मा। जुनन्ति। अहः ऽ अहः। अग्निना। आध्वर्यवं। वा। ब्र
७ ह्मा। संऽइत्। भवति। सा। आऽहुतिः। वा। अयं। यः। होता। किः। ऊँ इति। सः। यमस्य। कं। अपि। ऊहे। यत्। संऽअञ्ज
7 न्ति। देवाः। अहः ऽ अहः। जायते। मासि ऽ मासि। अथा। देवाः। दधिरे। हव्यऽवाहं। मां। अपऽक्लुकं। बहु। कृ
च्छ्रा। चरन्तं। अग्निः। विद्वान्। यज्ञं। नः। कल्पयाति। पंचऽयामं। त्रिऽवृतं। सप्तऽतंतुं। आ। वः। यक्षि। अमृत
त्वं। सुऽवीरं। यथा। वः। देवाः। वरिवः। कराणि। आ। बाह्वोः। वज्रं। इन्द्रस्य। धेयां। अथ। इमाः। विश्वाः। पृतनाः। जयाति। इत्या। यं।
ऐच्छाम। मनसा। सः। अयं। आ। अगात्। यज्ञस्य। विद्वान्। परुषः। चिकित्वान्। सः। नः। यक्षत्। देवऽताता। यजीयान्। नि। हि। सत्सत्। अं
तरः। पूर्वः। अस्मत्। अराधि। होता। निऽसद्। यजीयान्। अभि। प्रयांसि। सुऽधितानि। हि। ख्यत्।

वनोयस्य द्वेवनां जाय जीयार

देवादधि रे हव्युवा हे मथुमा विश्वाःएतं ना ७ श्री गिशः ओर्स्रः

© Dharmartha Trust J&K. Digitized by eGangotri

यजामहे।यज्ञियान्।हंत।देवान्।ईळामहे।ईड्यान्।आज्येन।साध्वीं।अकः।देवऽवीतिं।अद्य।नः।यज्ञस्य।
जिह्वां।अविदाम।गुह्यां।सः।आयुः।आ।अगात्।सुरभिः।वसानः।भद्रां।अकः।देवऽहूतिं।नः।अद्य।तत्।अद्य।
वाचः।प्रथमं।मसीय।येन।असुरान्।अभि।देवाः।असाम।ऊर्जऽअदः।उत।यज्ञियासः।पंच।जनाः।मम।
होत्रं।जुषध्वं।पंच।जनाः।मम।होत्रं।जुषंतां।गोतंतुं।तन्वन्।रजसः।भानुं।अनु।इहि।ज्योतिष्मतः।पथः।
रक्ष।धिया।कृतान्।अनुल्बणं।वयत।जोगुवां।अपः।मनुः।भव।जनय।दैव्यं।जनं।अक्षऽनहः।नह्यतन।
उत।सोम्याः।इष्कृणुध्वं।रशनाः।उत।पिंशत।अष्टाऽवंधुरं।वहत।अभितः।रथं।येन।देवासः।अनयन्।अ
भि।प्रियं।अश्मन्ऽवती।रीयते।सं।रभध्वं।उत्।तिष्ठत।प्र।तरत।सखायः।अत्र।जहाम।ये।असन्।अ
आ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ शेवाः।शिवा।नः।वयं।उत्।तारेम।अभि।वाजान्।त्वष्टा।मायाः।वेत्।अपसां।अपःऽतमः।बिभ्रत्।पात्रा।देवऽ
८ पानानि।शंऽतमा।शिशीते।नूनं।परशुं।सुऽआयसं।येन।वृश्चात्।एतशः।ब्रह्मणः।पतिः।सतः।नूनं।क
वयः।सं।शिशीत।वाशीभिः।याभिः।अमृताय।तक्षथ।विद्वांसः।पदा।गुह्यानि।कर्तन।येन।देवासः।अमृ
8 तऽत्वं।आनशुः।गर्भे।योषां।अदधुः।वत्सं।आसनि।अपीच्येन।मनसा।उत।जिह्वया।सः।विश्वाहा।सुऽ
मनाः।योग्याः।अभि।सिसासनिः।वनते।कारः।इत्।जितिं॥११॥तां।सु।ते।कीर्तिं।मघऽवन्।महिऽत्वा।
यत्।त्वा।भीते इति।रोदसी इति।अह्वयेतां।प्र।आवः।देवान्।आ।अतिरः।दासं।ओजः।प्रऽजायै।त्वस्यै।
यत्।अशिक्षः।इंद्र।यत्।अचरः।ववृधानः।बलानि।इंद्र।प्रऽब्रुवाणः।जनेषु।माया।इत्ता।सा। ८

© Dharmartha Trust J&K. Digitized by eGangotri

ता।यानि।युद्धानि।आहुः।न।अद्य।शत्रुं।ननु।पुरा।विवित्से।कः।अंग।इत्।नु।ते।महिमनः।समस्य।
अस्मत्।पूर्वे।ऋषयः।अंतं।आपुः।यत्।मातरं।च।पितरं।च।साकं।अजनयथाः।तन्वः।स्वायाः।
चत्वारि।ते।असुर्याणि।नाम।अदाभ्यानि।महिषस्य।संति।त्वं।अंग।तानि।विश्वानि।वित्से।
येभिः।कर्माणि।मघऽवन्।चकर्थ।त्वं।विश्वा।दधिषे।केवलानि।यानि।आविः।या।च।गुहा।व
सूनि।कामं।इत्।मे।मघऽवन्।मा।वि।तारीः।त्वं।आऽज्ञाता।त्वं।इंद्र।असि।दाता।यः।अधात्।
ज्योतिषि।ज्योतिः।अंतः।यः।असृजत्।मधुना।सं।मधूनि।अध।प्रियं।शूषं।इंद्राय।मन्म।ब्रह्मऽ
कृतः।बृहत्ऽउक्थात्।अवाचि।।इति।दूरे।तत्।नाम।गुह्यं।पराचैः।।अ ह्वयेतां।न।यः।धे।उत्।

। घां ।

तन्नाम गुह्यं

१०.अ अस्तभ्नाः।पृथिवीं।अभीके।भ्रातुः।पुत्रान्।मघऽवन्।तित्विषाणः॥महत्।तत्।पुरुऽस्पृक्।येन।भूतं।

१ जनयः।येन।भव्यं।प्रत्नं।जातं।ज्योतिः।यत्।अस्य।प्रियं।प्रियाः।सं।अविशंत।पंच॥आ।रोदसी

इति।अपृणात्।आ।उत।मध्यं।पंच।देवान्।ऋतुऽशः।सप्तऽसप्त।चतुःऽत्रिंशता।पुरुधा।वि।चष्टे।सऽ

रूपेण।ज्योतिषा।विऽव्रतेन।यत्।उषः।औच्छः।प्रथमा।विऽभानां।अजनयः।येन।पुष्टस्य।पुष्टं।यत्।

ते।जामिऽत्वं।अवरं।परस्याः।महत्।महत्याः।असुरऽत्वं।एकं॥विऽधुं।दद्राणं।समने।बहूनां।युवा

नं।संतं।पलितः।जगार।देवस्य।पश्य।काव्यं।महिऽत्वा।अद्य।ममार।सः।ह्यः।सं।आन॥५॥

शाक्मना।शाकः।अरुणः।सुऽपर्णः।आ।यः।महः।शूरः।सनात्।अनीळः।यत्।चिकेत।सत्यं।

© Dharmartha Trust J&K. Digitized by eGangotri

इत।तन्न।न।मोघं।वसु।स्पां।हिं।उन।जेता।उत।दाता।आ।एभिः।दृदे।रघ्या।पोंस्या।नि।ये।भिः।ओक्षन्त।
रत्नः।हत्याय।वज्री।यो।कर्मणः।क्रियमाणस्य।मन्हा।ऋतेऽकर्म।उत्ऽअजायन्त।देवाः।युजा।कर्माणि।
जनयन्न।विश्वऽओजाः।अशस्तिऽहा।विश्वऽमनाः।तुराषाट्।पीत्वी।सोमस्य।दिवः।आ।रधानः।शूर
रः।निः।युधा।अधमत।दस्यून्॥१७॥इदं।ते।एकं।परः।ऊंइति।ते।एकं।तृतीयेन।ज्योतिषा।सं।विशस्व।
संऽवेशने।तन्वः।चारुः।एधि।प्रियः।देवानां।परमे।जनित्रे।तन्वः।ते।वाजिन्न।तन्वं।नयन्ती।वामं।अस्मभ्यं।
धातु।शर्म।तुभ्यं।अहुतः।महः।धरुणाय।देवान्।दिविऽइव।ज्योतिः।स्वं।आ।मिमीयाः।वाजी।असि।
वाजिनेना।सुऽवेनीः।सुवितः।स्तोमं।सुवितः।दिवं।गाः।सुवितः।धर्म।प्रथमा।अनु।सत्या।सुवितः।

© Dharmartha Trust J&K. Digitized by eGangotri

प०अ० देवान्। सुवितः। अनु। प्रमा॥ महिम्नः। एषां। पितरः। चन। ईशिरे। देवाः। देवेषु। अदधुः। अपि। क्रतुं। सं। अवि
३० व्यचुः। उत। यानि। अत्विषुः। आ। एषां। तनूषु। नि। विविशुः। पुनरिति॥ सहःऽभिः। विश्वं। परि। चक्रमुः। रजः।
पूर्वा। धामानि। अमिता। मिमानाः। तनूषु। विश्वा। भुवना। नि। येमिरे। प्र। असारयंत। पुरुधा। प्रऽजाः। अ
नु॥ द्विधा। सूनवः। असुरं। स्वःऽविदं। आ। अस्थापयंत। तृतीयेन। कर्मणा। स्वां। प्रऽजां। पितरः। पित्र्यं।
सहः। आ। अवरेषु। अदधुः। तंतुं। आऽततं॥ नावा। न। क्षोदः। प्रऽदिशः। पृथिव्याः। स्वस्तिऽभिः। अति। दुः
ऽगानि। विश्वा। स्वां। प्रऽजां। बृहत्ऽउक्थः। महिऽत्वा। आ। अवरेषु। अदधात्। आ। परेषु॥ ३८॥ मा। प्र।
गाम। पथः। वयं। मा। यज्ञात्। इंद्र। सोमिनः। मा। अंतरिति। स्थुः। नः। अरातयः॥ यः। यज्ञस्य। प्रऽसाधनः। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

तंतुः। देवेषु। आऽततः। तं। आऽहुतं। नशीमहि। मनः। नु। आ। हुवामहे। नाराशंसेन। सोमेन। पितृणां।
च। मन्मऽभिः। आ। ते। एतु। मनः। पुनः। इति। क्रत्वे। दक्षाय। जीवसे॥ पुनः। नः। पितरः। मनः। ददातु।
दैव्यः। जनः। जीवं। व्रातं। सचेमहि॥ वयं। सोम। व्रते। तव। मनः। तनूषु॥ बिभ्रतः। प्रजाऽवंतः। सचेमहि॥ १॥
यत्। ते। यमं। वैवस्वतं। मनः। जगाम। दूरकं। तत्। ते। आ। वर्तयामसि। इह। क्षयाय। जीवसे। यत्। ते। दि
वं। यत्। पृथिवीं॥ यत्। ते। भूमिं। चतुःऽभृष्टिं॥ यत्। ते। चतस्रः। प्रऽदिशः॥ यत्। ते। समुद्रं। अर्णवं॥
यत्। ते। मरीचीः। प्रऽवतः॥ २॥ यत्। ते। अपः। यत्। ओषधीः॥ यत्। ते। सूर्यं। यत्। उषसं॥ यत्।
ते। पर्वतान्। बृहतः॥ यत्। ते। विश्वं। इदं। जगत्॥ यत्। ते। परः। पराऽवतः॥ यत्। ते। भूतं। च। भव्यं।

© Dharmartha Trust J&K. Digitized by eGangotri

१उअ· वा ॥ ०२१ ॥ प्र । तारि । आयुः । प्रऽतरं । नवीयः । स्थातारा ऽ इव । क्रतुऽमता । रथस्य । अध । च्यवानः । उत् ।
३३ तवीति । अर्थं । पराऽतरं । सु । निःऽऋतिः । जिहीतां ॥ सामन् । नु । राये । निधिऽमत् । नु । अन्नं । करामहे । सु ।
पुरुधा । श्रवांसि । ता । नः । विश्वानि । जरिता । ममत्तु ॥ ० ॥ अभि । सु । अर्यः । पौंस्यैः । भवेम । द्यौः । न । भूमिं ।
गिरयः । न । अज्रान् ॥ ० ॥ चिकेत ॥ ० ॥ मो इति । सु । नः । सोम । मृत्यवे । परा । दाः । पश्येम । नु । सूर्यं । उत्ऽचरंतं । द्युऽ
भिः । हितः । जरिमा । सु । नः । अस्तु ॥ ० ॥ असुऽनीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः ।
आयुः । रंधि । नः । सूर्यस्य । संऽदृशि । घृतेन । त्वं । तन्वं । वर्धयस्व ॥ २२ ॥ असुऽनीते । पुनः । अस्मासु ।
चक्षुः । पुनः । इति । प्राणं । इह । नः । धेहि । भोगं । ज्योक् । पश्येम । सूर्यं । उत्ऽचरंतं । अनुऽमते । मृळय । नः । ११

© Dharmartha Trust J&K. Digitized by eGangotri

स्वस्ति।पुनः।नः।असुं।पृथिवी।ददातु।पुनः।द्यौः।देवी।पुनः।अंतरिक्षं।पुनः।नः।सोमः।तन्वं।ददातु।
पुनरिति।पूषा।पथ्यां।या।स्वस्तिः।शं।रोदसीइति।सुऽबंधवे।यह्वीइति।ऋतस्य।मातरा।भरतां।
अप।यत्।रपः।द्यौः।पृथिवि।क्षमा।रपः।मोइति।सु।ते।किं।चन।आममत्।अव।ह्वकेइति।अव।त्रिका।
दिवः।चरंति।भेषजा।क्षमा।चरिष्णु।एककं।०।सं।इंद्र।ईरय।गां।अनड्वाहं।यः।आ।अवहत्।उशी
नराण्याः।अनः।०।।२२।।आ।जनं।त्वेषऽसंदृशं।माहीनानां।उपऽस्तुतं।अगन्म।बिभ्रतः।नमः।अ
समातिं।निऽतोशनं।त्वेषं।निऽययिनं।रथं।भजेऽरथस्य।सत्ऽपतिं।यः।जनान्।महिषान्ऽइव।
अतिऽतस्थौ।पवीरवान्।उत।अपवीरवान्।युधा।यस्य।इक्ष्वाकुः।उप।व्रते।रेवान्।मरायी।एध

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ नोदिविऽइवापंचास्तृत्य्यंःइंद्रास्त्राअसमातिष्ठारथंऽयोष्ठेषुधारयादिविऽइवास्त्सूर्यौदृशोअग
१२ स्त्यस्यानत्ऽभ्यःसप्नीइतिपुनक्षिरोहितापणीन्ानिअक्रमीःअभिविश्वान्राजन्अराध
सःा२४ाअयंमाताअयंपिताअयंजीवातुःआअगमत्इदंतववाप्रऽसर्पणंसुबंधोइतिसु
नि॰इहि बंधोआइहिंयथायुगंवरत्रयानह्यंतिधरुणायकंएवादाधारतेमनःजीवातवेनामृत्य
12 वेअथोइतिअरिष्टऽतातयेयथाइयंपृथिवीमहीदाधारइमान्वनस्पतीन्एयमालअ
हावैवस्वतातसुऽबंधोःमनःआअभरंन्यक्ववातःअववातिन्यक्तपतिसूर्यःनीचीने
अघ्न्यादुहान्यक्भवतुतेरपःअयंमेहस्तःभगऽवान्अयंमेभगवत्ऽतरःअयंमेविश्वऽ १२

© Dharmartha Trust J&K. Digitized by eGangotri

भेषजः। अयं। शिवःऽअभिमर्शनः॥ २५॥ अनुवाकः॥ इदं। इत्था। रौद्रं। गूर्तऽवचाः। ब्रह्म। क्रत्वा। शच्यां।
अंतः। आजौ। क्राणा। यत्। अस्य। पितरा। मंहनेऽस्थाः। पर्षत्। पक्थे। अहन्। आ। सप्त। होतॄन्। सः।
इत्। दानाय। दभ्याय। वन्वन्। च्यवानः। सूदैः। अमिमीत। वेदिं। तूर्वयाणः। गूर्तवचःऽतमः। क्षोदः।
न। रेतः। इतःऽऊति। सिंचत्। मनः। न। येषु। हवनेषु। तिग्मं। विपः। शच्या। वनुथः। द्रवंता। आ। यः। शर्या-
भिः। तुविऽनृम्णः। अस्य। अश्रीणीत। आऽदिशं। गभस्तौ। कृष्णा। यत्। गोषु। अरुणीषु। सीदत्।
दिवः। नपाता। अश्विना। हुवे। वां। वीतं। मे। यज्ञं। आ। गतं। मे। अन्नं। ववन्वांसा। न। इषं। अ-
स्मृतध्रू इत्यस्मृतऽध्रू। प्रथिष्ट। यस्य। वीरऽकर्मं। इष्णत्। अनुऽस्थितं। नु। नर्यः। अप। औहत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. पुनरिति। तत्। आ। वृहति। यत्। कनायाः। दुहितुः। आः। अनुऽभृतं। अनर्वा॥५॥ मध्या। यत्। कर्त्वं।
१३ अभवत्। अभीके। कामं। कृण्वाने। पितरि। युवत्यां। मनानक्। रेतः। जहतुः। विऽयंता। सानौ। निःऽसिक्तं।
सुऽकृतस्य। योनौ। पिता। यत्। स्वां। दुहितरं। अधिऽस्कन्। क्ष्मया। रेतः। संऽजग्मानः। नि। सिंचत्। सुऽआ
ध्यः। अजनयन्। ब्रह्म। देवाः। वास्तोः। पतिं। व्रतऽपां। निः। अतक्षन्। सः। ईं। वृषा। न। फेनं। अस्यत्। आजौ।
स्मत्। आ। परा। ऐत्। अप। दभ्रऽचेताः। सरत्। पदा। न। दक्षिणा। पराऽवृक्। न। ताः। नु। मे। पृशन्यः। जगृभ्रे।
13 मक्षु। न। वह्निः। प्रऽजायाः। उपब्दिः। अग्निं। न। नग्नः। उप। सीदत्। ऊधः। सनिता। इध्मं। सनिता। उत। वा
जं। सः। धर्ता। जज्ञे। सहसा। यविऽयुत्। मक्षु। कनायाः। सख्यं। नवऽग्वाः। ऋतं। वदंतः। ऋतऽयुक्तिं। अग्मन्। १३

© Dharmartha Trust J&K. Digitized by eGangotri

शुवि

ना। हिऽबर्हिसः। ये। उ। वा। गोपं। आ। अगुः। अदक्षिणासः। अच्युता। दु। भुक्षन्। आ। र ३०॥ गेन वीयः। रा पः। मसूकृना पोऽसू रंय।

नारेतः। त्रे ले। इत्ना। तुरण्यन्। प आ। य ता। प आ। यिऽयुता। बुधंना। इति। ब्रवीति। वक्तः। रि। र रा पः। ब

सोः। वसुऽत्वा। कारवः। अनेहा। विश्वं। विवेशि। द्रविणं। उप। स्तुत। इत्ना। अस्या। परि। स द्वानः

अगमन्। पुरा। सदंतः। नासंदा। विभिन्ना। विभुस्स्या। संऽगथितं। अनर्वा। विदत्। पुरुऽप्रजात

स्य। गुहा। यत्। अमर्गन्धं। हा। नाम। उत। यस्य। देवाः। स्वः। न। ये। त्रिऽसधस्थे। निऽसेदुः। अग्निः। ० जाने हमामोत

ऽवेदाः। श्रुधि। नः। होतः। ऋतस्य। होता। अध्रुक्। उत। या। मा। रौद्रौ। अर्चिऽमंता। नासत्यौ। इंद्राय

तेयै। यजे ध्यै। म। नु। घ ता। व स्कऽबर्हिषः। ररा णा। मंदू। इति। हितऽप्रयसा। विक्षु। यज्यू। इति। ॥ २८॥

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ अयं। स्तुतः। राजा। वंदि। वेधाः। अपः। च। विप्रः। तरति। स्वऽसेतुः। सः। कक्षीवंतं। रेजयत्। सः। अ
१४ ग्निं। नेमिं। न। चक्रं। अर्वतः। रघुऽद्रु। सः। द्विऽबंधुः। वैतरणः। यष्टा। सबःऽधुं। धेनुं। अस्वं। दुहध्यै।
14 सं। यत्। मित्रावरुणा। वृंजे। उक्थैः। ज्येष्ठेभिः। अर्यमणं। वरूथैः। तत्। नृऽबंधुः। सूरिः। दिवि। ते।
धियंऽधाः। नाभा। नेदिष्ठः। रपति। प्र। वेनन्। सा। नः। नाभिः। परमा। अस्य। वा। घ। अहं। तत्। पश्चा।
कतिथः। चित्। आस। इयं। मे। नाभिः। इह। मे। सधऽस्थं। इमे। मे। देवाः। अयं। अस्मि। सर्वः। द्विऽजाः।
अह। प्रथमऽजाः। ऋतस्य। इदं। धेनुः। अदुहत्। जायमाना। अध। आसु। मंद्रः। अरतिः। विभाऽ
वा। अव। स्यति। द्विऽवर्तनिः। वने। षाट्। ऊर्ध्वा। यत्। श्रेणिः। न। शिशुः। दन्। मक्षु। स्थिरं। शेऽवृधं। ३४

© Dharmartha Trust J&K. Digitized by eGangotri

सुता। मा। ना॥ २१॥ अध। गाः। उपऽमातिं। कनायाः। अनु। श्वांतस्य। कस्य। चित्। परा। ईयुः।
श्रुधि। त्वं। सुऽद्रविणः। नः। त्वं। याट्। आश्वऽघ्नस्य। वरधे। सूनृताभिः। अध। त्वं। इंद्र। विद्धि।
अस्मान्। महः। रायः। नृऽपते। वज्रऽबाहुः। ०। अनेहसः। ते। हरिऽवः। अभिष्टौ। अध। यत्। राजा। रक्षो च नो मघोनः पाहि सूरीन्
ना। गोऽइष्टौ। सरत्। सरण्युः। कारवे। जरण्युः। विप्रः। प्रेष्ठः। सः। हि। एषां। बभूव। परा। च। वक्ष-
त्। उत। पर्षत्। एना॥ अध। नु। अस्य। जेन्यस्य। पुष्टौ। रथः। रेभंतः। ईमहे। त्वे। ऊं इति। नु। सर-
ण्युः। अस्य। सूनुः। अश्व्यः। विप्रः। च। असि। श्रवसः। च। सातौ। युवोः। यदि। सख्याय। अस्मे
इति। शर्द्धाय। स्तोमं। जुजुषे। नमस्वान्। विश्वत्रा। यस्मिन्। आ। गिरः। संऽईचीः। पूर्वीःऽइव।

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. गातुः।दाशत्।सूनृतायै।सः।रणानः।अतऽभिः।देवऽवान्।इति।सुऽबंधुः।नमसा।सुऽउक्थैः।
१५ वर्धत्।उक्थैः।वचःऽभिः।आ।हि।नूनं।वि।अध्वा।एति।पयसः।उस्रियायाः।नो।ऊं इति।सूनुः।
मह्नः।यजत्राः।भूत।देवाः।सुऽऊत।ये।सऽजोषाः।ये।वाजान्।अनयत।विऽयंतः।ये।स्थ।निऽचेतारः।
अमूराः।।३०।।इति अष्टमाष्टके प्रथमोध्यायः।।ओं।।ये यज्ञेनैकादशाद्याः षळंगिरसां स्तुति
र्वींस्यास्त्रिष्टुप्पंचम्यनुष्टुप्प्रगाथोनुष्टुभौ गायत्री चतस्रोंत्याः सावर्णेर्दानस्तुतिः परावतस्त्यू
नागयः प्लातो द्वित्रिष्टुबंतंतु स्वस्ति नस्त्रिष्टुब्वा सा सहोतरया पथ्या स्वस्ति देवत्या कथा यां मे त्रि
ष्टुबग्निरिंद्रः पंचोना वसुकर्णो वासुक्रस्त्रिष्टुबंतंतु देवानु कुवइमां धियं द्वादशायास्यो बार्हस्प १५

15

© Dharmartha Trust J&K. Digitized by eGangotri

यंतद्दत्तुलो।भद्राः सुमित्रो वाध्र्यश्च आग्नेयं द्वि जगत्यादीमां मएकादशाग्रं बृहस्पतेर्बृहस्पतिर्ग्री
नं तुष्टावं नवमी जगती॥ हरिः ॐ॥ मा।ये।यज्ञेन।दक्षिणया।संऽअक्ताः।इंद्रस्य।सख्यं।अमृतऽत्वं।
आनश।तेभ्यः।भद्रं।अंगिरसः।वः।अस्तु।प्रति।गृभ्णीत।मानवं।सुऽमेधसः।ये।उतऽआजनि।पि
तरः।गोऽमयं।वसु।ऋतेन।अभिंदन्।परिवत्सरे।वलं।दीर्घायुऽत्वं।०।ये।ऋतेन।सूर्यं।आ।अरोह
यन्।दिवि।अप्रथयन्।पृथिवीं।मातरं।वि।सुऽप्रजाःऽत्वं।०।अयं।नाभा।वदति।वल्गु।वः।गृहे।देवऽ
पुत्राः।ऋषयः।तत्।शृणोतन।सुऽब्रह्मण्यं।०।विऽरूपासः।इत्।ऋषयः।ते।इत्।गंभीरऽवेपसः।ते।
अंगिरसः।सूनवः।ते।अग्नेः।परि।जज्ञिरे॥३॥ये।अग्नेः।परि।जज्ञिरे।विऽरूपासः।दिवः।परि।

© Dharmartha Trust J&K. Digitized by eGangotri

१०अ· नवऽग्वः। नु। दशऽग्वः। अंगिरःऽतमः। सचा। देवेषु। मंहते। इंद्रेण। युजा। निः। सृजंत। वाघतः। ०। सहस्रे।
३८ मे। दद्तः। अष्टऽकर्ण्यः। ०। प्र। नूनं। जायतां। अयं। मनुः। तोक्मऽइव। रोहतु। यः। सहस्रं। शतऽअश्वं। स।
द्यः। दानाय। मंहते। न। तं। अश्नोति। कः। चन। दिवःऽइव। सानु। आऽरभं। सावर्ण्यस्य। दक्षिणा। वि। सिं
16 धुःऽइव। पप्रथे। उत। दासा। परिऽविषे। स्मत्ऽदिष्टी। इति स्मत्ऽदिष्टी। गोऽपरीणसा। यदुः। तुर्वः। च। मम
हा। सहस्रऽदाः। ग्रामऽनीः। मा। रिषत्। मनुः। सूर्येण। अस्य। यतमाना। एतु। दक्षिणा। सावर्णेः। दे
वाः। प्र। अतिरंत। आयुः। यस्मिन्। अश्रांताः। असनाम। वाजं।।रा। पराऽवतः। ये। दिधिषंते। आप्यं।
मनुऽप्रीतासः। जनिम। विवस्वतः। ययातेः। ये। नहुष्यस्य। बर्हिषि। देवाः। आसते। ते। अधि। ब्रुवंतु। नः। ३८

© Dharmartha Trust J&K. Digitized by eGangotri

विश्वा।हि।वः।नमस्यानि।वंद्या।नामानि।देवाः।उत।यज्ञियानि।वः।ये।स्थ।जाताः।अदितेः।अत्ऽ
भ्यः।परि।ये।पृथिव्याः।ते।मे।इह।श्रुत।हवं।येभ्यः।माता।मधुऽमत्।पिन्वते।पयः।पीयूषं।द्यौः।अद्रिऽब अदितिः।
र्हाः।उक्थऽशुष्मान्।वृषऽभरान्।सुऽअप्नसः।तान्।आदित्यान्।अनु।मद।स्वस्तये।नृऽचक्षसः।अनिऽमि
षतः।अर्हणा।बृहत्।देवासः।अमृतऽत्वं।आनशुः।ज्योतिःऽरथाः।अहिऽमायाः।अनागसः।दिवः।वर्ष्माणं।
वसते।स्वस्तये।संऽराजः।ये।सुऽवृधः।यज्ञं।आऽययुः।अपरिऽह्वृताः।दधिरे।दिवि।क्षयं।तान्।आ।वि
वास।नमसा।सुवृक्तिऽभिः।महः।आदित्यान्।अदितिं।स्वस्तये॥३॥कः।वः।स्तोमं।राधति।यं।जुजो
षथ।विश्वे।देवासः।मनुषः।यति।स्थन।कः।वः।अध्वरं।तुविऽजाताः।अरं।करत्।यः।नः।पर्षत्।अति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ अंहः। स्वस्तये। येभ्यः। होत्रां। प्रथमां। आऽयेजे। मनुः। समिद्धऽअग्निः। मनसा। सप्त। होतृऽभिः। ते। आ
३८ दित्याः। अभयं। शर्म। यच्छत। सुऽगा। नः। कर्त। सुऽपथा। स्वस्तये। ये। ईशिरे। भुवनस्य। प्रऽचेतसः। वि
श्वस्य। स्थातुः। जगतः। च। मंतवः। ते। नः। कृतात्। अकृतात्। एनसः। परि। अद्य। देवासः। पिपृत। स्वस्तये।
भरेषु। इंद्रं। सुऽहवं। हवामहे। अंहःऽमुचं। सुऽकृतं। दैव्यं। जनं। अग्निं। मित्रं। वरुणं। सातये। भगं। द्यावापृथि
वी इति। मरुतः। स्वस्तये। सुऽत्रामाणं। पृथिवीं। द्यां। अनेहसं। सुऽशर्माणं। अदितिं। सुऽप्रनीतिं। दैवीं। ना
वं। सुऽअरित्रां। अनागसं। अस्रवंतीं। आ। रुहेम। स्वस्तये॥४॥ विश्वे। यजत्राः। अधि। वोचत। ऊतये।
त्रायध्वं। नः। दुःऽएवायाः। अभिऽह्रुतः। सत्यया। वः। देवऽहूत्या। हुवेम। शृण्वतः। देवाः। अवसे। स्वस्तये। ३८

© Dharmartha Trust J&K. Digitized by eGangotri

अप। अमीवां। अप। विश्वां। अनाहुतिं। अप। अरातिं। दुःऽविदत्रां। अप। यत। नः। आरात्। देवाः। द्वेषः।
अस्मत्। युयोतन। उरु। नः। शर्म। यच्छत। स्वस्तये। अरिष्टः। सः। मर्तः। विश्वः। एधते। प्र। यं। आ [प्र प्रजाभिः]
दित्यासः। नयथ। सुनीतिऽभिः। अति। विश्वानि। दुःऽइता। स्वस्तये। यं। शूरऽसाता। मरुतः। हिते। [यं देवासो वथ।]
धने। प्रातःऽयावानं। रथं। इन्द्र। सानसिं। अरिष्यंतं। आ। रुहेम। स्वस्तये। स्वस्ति। नः। पथ्यासु। धन्वऽ
सु। स्वस्ति। अपऽसु। वृजने। स्वःऽवति। स्वस्ति। नः। पुत्रऽकृथेषु। योनिषु। स्वस्ति। राये। मरुतः। दधा
तन। स्वस्तिः। इत्। हि। प्रऽपथे। श्रेष्ठा। रेक्णस्वती। अभि। या। वामं। एति। सा। नः। अमा। सोइति। अ
रणे। नि। पातु। सुऽआवेशा। भवतु। देवऽगोपा। एव। प्लुते। सूनुः। अवीरऽपत। वः। विश्वे। आदित्याः। अदि

© Dharmartha Trust J&K. Digitized by eGangotri

प· अ· ते। मनीषी। ईशानासः। नरः। अमर्त्येन। अस्तावि। जनः। दिव्यः। गयेन॥ ५॥ कथा। देवानां। कतमस्य। या
१८ मनि। सुऽमंतु। नाम। शृण्वतां। मनामहे। कः। मृळाति। कतमः। नः। मयः। करत्। कमः। ऊती। अभि। आ। त
18 ववर्तति। क्रतुऽयंति। क्रतवः। हृत्ऽसु। धीतयः। वेनंति। वेनाः। पतयंति। आ। दिशः। न। मर्डिता। विद्यते।
अन्यः। एभ्यः। देवेषु। मे। अधि। कामाः। अयंसत। नराशंसं। वा। पूषणं। अगोह्यं। अग्निं। देवऽइद्धं। अ
भि। अर्चसे। गिरा। सूर्यामासा। चंद्रमसा। यमं। दिवि। त्रितं। वातं। उषसं। अक्तुं। अश्विना। कथा। क
विः। तुविऽरवान्। कया। गिरा। बृहस्पतिः। ववृधते। सुवृक्तिऽभिः। अजः। एकऽपात्। सुऽहवेभिः। ऋ
क्वऽभिः। अहिः। शृणोतु। बुध्न्यः। हवीमनि। दक्षस्य। वा। अदिते। जन्मनि। व्रते। राजाना। मित्रावरुणा। आ। १८

© Dharmartha Trust J&K. Digitized by eGangotri

विवाससि। अन्तर्नेऽ पंथाः। पुरुऽरथः। अर्यमा। सप्तऽहोता। विषुऽरूपेषु। जन्मऽसु।। ते। नः। अर्वंतः। हव
नऽश्रुतः। हवं। विश्वे। शृण्वंतु। वाजिनः। मितऽद्रवः। सहस्रऽसाः। मेधसाताऽइव। त्मना। महः। ये। धनं। सं
इथेषु। जभ्रिरे। पुरंऽधिं। स्तोमैः। कृणुध्वं। सख्याय। पूषणं। ते। हि। देवस्य। सवितुः। सवीमनि। क्रतुं।
सचंते। सऽचितः। सऽचेतसः। त्रिः। सप्त। सस्राः। नद्यः। महीः। अपः। वनस्पतीन्। पर्वतान्। अग्निं। ऊत
ये। कृशानुं। अस्तॄन्। तिष्यं। सधऽस्थे। आ। रुद्रं। रुद्रेषु। रुद्रियं। हवामहे। सरस्वती। सरयुः। सिंधुः। ऊर्मिऽ
भिः। महः। महीः। अवसा। आ। यंतु। वक्षणीः। देवीः। आपः। मातरः। सूदयित्न्वः। घृतऽवत्। पयः। मधुऽ
मत्। नः। अर्चत। उत। माता। बृहत्ऽदिवा। शृणोतु। नः। त्वष्टा। देवेभिः। जनिऽभिः। पिता। वचः। ऋभुक्षाः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. वाजः। रथःऽपतिः। भगः। रण्वः। शंसः। शशमानस्य। पातु। नः॥ ७॥ ०भद्रा। रुद्राणां। मरुतां। उपऽस्तु
१९ तिः। गोभिः। स्याम। यशसः। जनेषु। आ। सदा। देवासः। इळया। सचेमहि। यां। मेधियां। मरुतः। इं
19 द्र। देवाः। अददात। वरुण। मित्र। यूयं। तां। पीपयत। पयसाऽइव। धेनुं। कुवित्। अंग। प्रति। यथा। चित्। अस्य। नः। सऽजात्यस्य। मरुतः। बुबोधथ। नाभा। यत्र। प्रथ
मं। सं। नसामहे। तत्र। जामिऽत्वं। अदितिः। दधातु। नः॥ ०माता। मही इति। देवी इति। देवान्। जन्मना।
यज्ञिये इति। इतः। उभे इति। बिभृतः। उभयं। भरीमऽभिः। पुरु। रेतांसि। पितृऽभिः। च। सिंचतः। वि। सा।
होत्रा। विश्वं। अश्नोति। वार्यं। बृहस्पतिः। अरमतिः। पनीयसी। ग्रावा। यत्र। मधुऽसुत्। उच्यते। बृहत्। १९

© Dharmartha Trust J&K. Digitized by eGangotri

अवीवशंत। मतिऽभिः। मनीषिणः। एव। कविऽभिः। तुविऽरवान्। ऋतऽज्ञाः। द्रविणस्युः। द्रविणसः। चकानः।
गुर्वेष्ठेभिः। अत्र। मतिऽभिः। चा। विप्रः। अपीपयत्। गयः। दिव्यानि। जन्म॥ ० ॥ ७ ॥ अग्निः। इंद्रः। वरुणः। मि-
त्रः। अर्यमा। वायुः। पूषा। सरस्वती। सऽजोषसः। आदित्याः। विष्णुः। मरुतः। स्वः। बृहत्। सोमः। रुद्रः। अ-
दितिः। ब्रह्मणः। पतिः। इंद्राग्नी इति। वृत्रऽहत्येषु। सत्पती इति सत्ऽपती। मिथः। हिन्वाना। तन्वा। सं। ओ-
कसा। अंतरिक्षं। मही। आ। पप्रुः। ओजसा। सोमः। घृतऽश्रीः। महिमानं। ईरयन्। तेषां। हि। मन्हा। मह-
तः। अनर्वणां। स्तोमान्। इयर्मि। ऋतऽज्ञाः। ऋतऽवृधः। ये। अप्सवं। अर्णवं। चित्रऽराधसः। ते। नः। रा-
संतां। महये। सुऽमित्र्याः। स्वः। नरं। अंतरिक्षाणि। रोचना। द्यावाभूमी इति। पृथिवीं। स्कंभुः। ओज-

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ सा। पृक्षाःऽइवा। महय्यंतः। सुऽरातयः। देवाः। स्तवंते। मनुषाय। सूरयः। मित्राय। शिक्ष। वरुणाय। दा

२० शुषे। या। संऽराजा। मनसा। न। प्रऽयुछंतः। ययोः। धाम। धर्मणा। रोचते। बृहत्। ययोः। उभे इति।

20 रोदसी इति। नाधसी इति। वर्तौ॥ १॥ या। गोः। वर्तनिं। परिऽएति। निःऽकृतं। पयः। दुहाना। व्रतऽनीः।

अवारतः। सा। प्रऽब्रुवाणा। वरुणाय। दाशुषे। देवेभ्यः। दाशत्। हविषा। विवस्वते। दिवक्षसः। अग्निऽ

जिह्वाः। ऋतऽरधः। ऋतस्य। योनिं। विऽमृशंतः। आसते। यां। स्कभित्वी। अपः। आ। चक्रुः। ओजसा।

यज्ञं। जनित्वी। तन्वि। नि। ममृजुः। परिऽक्षिता। पितरा। पूर्वजावरी इति पूर्वऽजावरी। ऋतस्य। यो

ना। क्षयतः। संऽऊकसा। द्यावा। पृथिवी इति। वरुणाय। सम्राजे इति सम्ऽराजे। घृतऽवता। पयः। महिषाय। २०

© Dharmartha Trust J&K. Digitized by eGangotri

पिन्वतः। पर्जन्यावाता। वृषभा। पुरीषिणा। इंद्रवायू इति। वरुणः। मित्रः। अर्यमा। देवान्। अदितिं। ह आ दित्सान

वामहे। ये। पार्थिवासः। दिव्यासः। अप्ऽसु। ये। त्वष्टारं। वायुं। ऋभवः। यः। ओहते। दैव्या। होतारा। उष ह

सं। स्वस्तये। बृहस्पतिं। वृत्रऽखादं। सुऽमेधसं। इंद्रियं। सोमं। धनऽसाः। ऊं इति। ईमहे। १०। ब्रह्म। गां।

अश्वं। जनयंतः। ओषधीः। वनस्पतीन्। पृथिवीं। पर्वतान्। अपः। सूर्यं। दिवि। रोहयंतः। सुऽदानवः। आ

र्यां। व्रता। विऽसृजंतः। अधि। क्षमि। भुज्युं। अंहसः। पिपृथुः। निः। अश्विना। श्यावं। पुत्रं। वध्रिऽमत्याः।

अजिन्वतं। कमऽद्युवं। विऽमदाय। ऊहथुः। युवं। विष्णाप्वं। विश्वकाय। अव। सृजथः। पावीरवी। त

न्यतुः। एकऽपात्। अजः। दिवः। धर्ता। सिंधुः। आपः। समुद्रियः। विश्वे। देवासः। शृणवन्। वचांसि। मे।

© Dharmartha Trust J&K. Digitized by eGangotri

मनौः

प·अ· सरस्वती । सह । धीभिः । पुरंऽध्या । विश्वे । देवाः । सह । धीभिः । पुरंऽध्या । ँ । रातिऽसाचः । अभिऽसाचः । स्वः ऽ

२३ विदः । स्वः । गिरः । ब्रह्म । सुऽउक्तं । जुषेरत । देवान् । वसिष्ठः । अमृतान् । ववंदे । ये । विश्वा । भुवना । अभि ।

21 प्रऽतस्थुः । ँ । ३ । देवान् । हुवे । बृहत्ऽश्रवसः । स्वस्तये । ज्योतिःऽकृतः । अध्वरस्य । प्रऽचेतसः । ये । ववृ तनौ

धुः । प्रऽतरं । विश्वऽवेदसः । इंद्रऽज्येष्ठासः । अमृताः । ऋतऽवृधः । इंद्रऽप्रसूताः । वरुणऽप्रशिष्टाः । ये । सूर्यस्य ।

ज्योतिषः । भागं । आनशुः । मरुत्ऽगणे । वृजने । मन्म । धीमहि । माघोने । यज्ञं । जनयंत । सूरयः । इंद्रः । वसुऽ

भिः । परि । पातु । नः । गयं । आदित्यैः । नः । अदितिः । शर्म । यच्छतु । रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा ।

नः । ग्नाभिः । सुऽवितायः । जिन्वतु । अदितिः । द्यावापृथिवी इति । ऋतं । महत् । इंद्राविष्णू इति । मरुतः । स्वः । २३

© Dharmartha Trust J&K. Digitized by eGangotri

बृहत्। देवान्। आदित्यान्। अवसे। हवामहे। वसून्। रुद्रान्। सवितारं। सुऽदंससं। सरस्वान्। धीभिः।
वरुणः। धृतऽव्रतः। पूषा। विष्णुः। महिमा। वायुः। अश्विना। ब्रह्मऽकृतः। अमृताः। विश्वऽवेदसः। शर्म।
नः। यंसन्। त्रिऽवरूथं। अंहसः॥ २॥ वृषा। यज्ञः। वृषणः। सन्तु। यज्ञियाः। वृषणः। देवाः। वृषणः। हविःऽ
कृतः। वृषणा। द्यावापृथिवी इति। ऋतवरी इत्यृतऽवरी। वृषा। पर्जन्यः। वृषणः। वृषऽस्तुभः। अग्नीषोमा।
वृषणा। वाजऽसातये। पुरुऽप्रशस्ता। वृषणौ। उप। ब्रुवे। यौ। ईजिरे। वृषणः। देवऽयज्यया। ता। नः। शर्म।
त्रिऽवरूथं। वि। यंसतः। धृतऽव्रताः। क्षत्रियाः। यज्ञनिःऽकृतः। बृहत्ऽदिवाः। अध्वराणां। अभिऽश्रियः।
अग्निऽहोतारः। ऋतऽसापः। अद्रुहः। अपः। असृजन्। अनु। वृत्रऽतूर्ये। द्यावापृथिवी इति। जनयन्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ अभि। व्रता। आपः। ओषधीः। वनिनः। यज्ञिया। अंतरिक्षं। स्वः। आ। पप्रुः। ऊतये। वशं। देवासः।
२२ तन्वि। नि। म मृजुः। धर्त्तारः। दिवः। ऋभवः। सुऽहस्ताः। वाता। पर्जन्या। महिषस्य। तन्यतोः। आपः। ओष
धीः। प्र। तिरंतु। नः। गिरः। भगः। रातिः। वाजिनः। यंतु। मे। हवं। ३३। समुद्रः। सिंधुः। रजः। अंतरिक्षं। अजः।
एकऽपात्। तनयित्नुः। अर्णवः। अहिः। बुध्न्यः। शृणवत्। वचांसि। मे। विश्वे। देवासः। उत। सूरयः। मम।
स्याम। नः। मनवः। देवऽवीतये। प्रांचं। नः। यज्ञं। प्र। नयत। साधुऽया। आदित्याः। रुद्राः। वसवः। सुऽदान
वः। इमा। ब्रह्म। शस्यमानानि। जिन्वत। ३४। पुरःऽहिता। ऋतस्य। पंथां। अनु। एमि। साधुऽया। क्षेत्रस्य।
पतिं। प्रतिऽवेशं। ईमहे। विश्वान्। देवान्। अमृतान्। अप्रऽयुच्छतः। वसिष्ठासः। पितृऽवत्। वाचं। अ २२

दैव्या हानो

© Dharmartha Trust J&K. Digitized by eGangotri

देवान्वसिष्ठः क्रत। देवान्। ईळ्हानाः। ऋषिऽवत्। स्वस्तये। प्रीताःऽइव। ज्ञातयः। कामं। आऽइत्य। अस्मे इति। देवासः।
अव। धूनुत। वसु॥ ॥ १४॥ इमां। धियं। सप्तऽशीर्ष्णीं। पिता। नः। ऋतऽप्रजातां। बृहतीं। अविंदत्।
तुरीयं। स्वित्। जनयत्। विश्वऽजन्यः। अयास्यः। उक्थं। इंद्राय। शंसन्॥ ऋतं। शंसंतः। ऋजु। दीध्या-
दिवस्पुत्रासो नाः॥ ॥ विप्रं। पदं। अंगिरसः। दधानाः। यज्ञस्य। धाम। प्रथमं। मनंत॥ हंसैःऽइव। सखिऽभिः। वावदत्ऽ-
भिः। अश्मन्ऽमयानि। नहना। विऽअस्यन्। बृहस्पतिः। अभिऽकनिक्रदत्। गाः। उत। प्र। अस्तौत्। उ-
त्। च। विद्वान्। अगायत्॥ अवः। द्वाभ्यां। परः। एकया। गाः। गुहा। तिष्ठंतीः। अनृतस्य। सेतौ। बृहस्प-
तिः। तमसि। ज्योतिः। इच्छन्। उत्। उस्राः। आ। अकः। वि। हि। तिस्रः। आवरित्यावः। विऽभिद्य। पुरा। शयथा।

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. ई।अपाचीं।निः।त्रीणि।साकं।उदऽधेः।अकृंतत्।बृहस्पतिः।उषसं।सूर्यं।गां।अर्कं।विवेद।स्तनय
२३ न्ऽइव।द्यौः।इंद्रः।वलं।रक्षितारं।दुघानां।करेणऽइव।वि।चकर्त्त।रवेण।स्वेदांजिऽभिः।आऽशिरं।इ
च्छमानः।अरोदयत्।पणिं।आ।गाः।अमुष्णात्।।३५।।सः।ईं।सत्येभिः।सखिऽभिः।शुचत्ऽभिः।गोऽधा
23
यसं।वि।धनऽसैः।अदर्दरित्यदर्दः।ब्रह्मणः।पतिः।वृषऽभिः।वराहैः।घर्मऽस्वेदेभिः।द्रविणं।वि।आन
ट्।ते।सत्येन।मनसा।गोऽपतिं।गाः।इयाना।सः।इषणयंत।धीभिः।बृहस्पतिः।मिथःऽअवद्यपेभिः।
उत्।उस्रियाः।असृजत।स्वयुक्ऽभिः।तं।वर्द्धयंतः।मतिऽभिः।शिवाभिः।सिंहंऽइव।नानदतं।सधऽ
स्थे।बृहस्पतिं।वृषणं।शूरऽसातौ।भरेऽभरे।अनु।मदेम।जिष्णुं।यदा।वाजं।असनत्।विश्वऽरूपं। २३

© Dharmartha Trust J&K. Digitized by eGangotri

आ। यां। अत्सस्य। उत्ऽतराणि। सप्त। बृहस्पतिं। वृषणं। वर्द्धयंतः। नाना। संतः। बिभ्रतः। ज्योतिः। आसा।
सत्यां। आऽशिषं। कृणुत। वयःऽधै। कीरिं। चित्। हि। अवथ। स्वेभिः। एवैः। पश्चा। मृधः। अप। भवंतु। विश्वाः।
तत्। रोदसी इति। शृणुतं। विश्वमिन्वे इति विश्वंऽइन्वे। इंद्रः। मह्ना। महतः। अर्णवस्य। वि। मूर्द्धानं। अभिनत्।
अहुभहि अर्बुदस्य।।१०।।३१।। उद्ऽप्रुतः। न। वयः। रक्षमाणाः। वावदतः। अभ्रियस्यऽइव। घोषाः। गिरिऽभ्रजः। न। ऊ
र्मयः। मदंतः। बृहस्पतिं। अभि। अर्काः। अनावन्। सः। गोभिः। आंगिरसः। न। क्षमाणः। भगःऽइव। इत्। अर्य
मणं। निनाय। जने। मित्रः। न। दंपती इति दंऽपती। अनक्ति। बृहस्पते। वाजय। आशून्ऽइव। आजौ। सा
धुऽअर्याः। अतिथिनीः। इषिराः। स्पार्हाः। सुऽवर्णाः। अनवद्यऽरूपाः। बृहस्पतिः। पर्वतेभ्यः। विऽतूर्य। निः

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ गाः। कूपात्। यवंऽइव। स्थिविऽभ्यः। आऽप्रुषायन्। मधुना। ऋतस्य। योनिं। अवऽक्षिपन्। अर्कः। उल्कांऽइव।
२४ द्योः। बृहस्पतिः। उद्धरन्। अश्मनः। गाः। भूम्याः। उद्नाऽइव। वि। त्वचं। बिभेद। अप। ज्योतिषा। तमः। अंतरिक्षात्।
उद्नः। शीपालंऽइव। वातः। आ। अजत्। बृहस्पतिः। अनुऽमृश्य। वलस्य। अभ्रंऽइव। वातः। आ। चक्रे। आ। गाः। यदा।
वलस्य। पीयतः। जसुं। भेत्। बृहस्पतिः। अग्नितपःऽभिः। अर्कैः। दत्ऽभिः। न। जिह्वा। परिऽविष्टं। आदत्। आ।
विः। निःऽधीन्। अकृणोत्। उस्रियाणां॥ ३॥ बृहस्पतिः। अमत। हि। त्यत्। आसां। नाम। स्वरीणां। सदने।
गुहा। यत्। आंडाऽइव। भित्वा। शकुनस्य। गर्भं। उत्। उस्रियाः। पर्वतस्य। त्मना। आजत्। अश्ना। अपिऽनद्धं।
मधु। परि। अपश्यत्। मत्स्यं। न। दीने। उदनि। क्षियंतं। निः। तत्। जभार। चमसं। न। वृक्षात्। बृहस्पतिः। वि

© Dharmartha Trust J&K. Digitized by eGangotri

ऽरवेण। विऽरवः स्यां। सः। उषां। अविंदत्। सः। स्वः। इति। स्वः। सः। अग्निं। सः। अर्केण। वि। बबाधे। तमांसि। बृह
स्पतिः। गोऽवपुषः। वलस्य। निः। मज्जानं। न। पर्वणः। जभार। हिमाऽइव। पर्णा। मुषिता। वनानि। बृहस्प
तिना। अकृपयत्। वलः। गाः। अननुऽकृत्यं। अपुनरिति। चकार। यात्। सूर्यामासा। मिथः। उत्ऽचरा
तः। अभि। श्यावं। न। कृशनेभिः। अश्वं। नक्षत्रेभिः। पितरः। द्यां। अपिंशन्। रात्र्यां। तमः। अदधुः। ज्योतिः।
अहन्। बृहस्पतिः। भिनत्। अद्रिं। विदत्। गाः। इदं। अकर्म। नमः। अभ्रियाय। यः। पूर्वीः। अनु। आऽ
नोनवीति। बृहस्पतिः। सः। हि। गोभिः। सः। अश्वैः। सः। वीरेभिः। सः। नृऽभिः। नः। वयः। धात्। ३८। भद्राः।
अग्नेः। वध्रिऽअश्वस्य। संऽदृशः। वामी। प्रऽनीतिः। सुऽरणाः। उपऽइतयः। यत्। ईं। सुऽमित्राः। विशः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. ग्रे। इंधते। घृतेन। आऽहुतः। जरते। दविद्युतत्। घृतं। अग्नेः। वध्रिऽअश्वस्य। वर्द्धनं। घृतं। अन्नं। घृतं। ऊं इ
२५ ति। अस्य। मेदनं। घृतेन। आऽहुतः। उर्विया। वि। पप्रथे। सूर्यःऽइव। रोचते। सर्प्पिःऽआसुतिः। यत्। ते। मनुः।
यत्। अनीकं। सुऽमित्रः। संऽईधे। अग्ने। तत्। इदं। नवीयः। सः। रेवत्। शोच। सः। गिरः। जुषस्व। सः। वाजं। दर्षि।
सः। इह। श्रवः। धाः। यं। त्वा। पूर्वं। ईळितः। वध्रिऽअश्वः। संऽईधे। अग्ने। सः। इदं। जुषस्व। सः। नः। स्तिऽपाः।
उत। भव। तनूऽपाः। दात्रं। रक्षस्व। यत्। इदं। ते। अस्मे इति। भव। द्युम्नी। वाध्रिऽअश्व। उत। गोपाः। मा।
त्वा। तारीत्। अभिऽमातिः। जनानां। शूरःऽइव। धृष्णुः। च्यवनः। सुऽमित्रः। प्र। नु। वोचं। वाध्रिऽअश्व
स्य। नाम। सं। अज्र्या। पर्वत्या। वसूनि। दासा। वृत्राणि। आर्य्या। जिगेथ। ० जनानां। त्वं। अग्ने। पृतनाऽ २५

शूरःऽइव धृष्णुः।

© Dharmartha Trust J&K. Digitized by eGangotri

यून्।अभि।स्याः॥१०॥दीर्घंऽतंतुः।बृहत्ऽउक्षा।अयं।अग्निः।सहस्रिणः।सहस्रःऽस्तरीः।शतऽनीथः।ऋभ्वा।
द्युऽमान्।द्युमत्ऽस्तु।न्तऽभिः।मृज्यमानः।सुऽमित्रेषु।दीदयः।देवयत्ऽसु।स्वे।इति।धेनुः।सुऽदुघा।
जातऽवेदः।असश्चताऽइव।समना।सबःऽधुक्।त्वां।नृऽभिः।दक्षिणावत्ऽभिः।अग्ने।सुऽमित्रेभिः।
इध्यसे।देवयत्ऽभिः।देवाः।चित्।ते।अमृताः।जातऽवेदः।महिमानं।वाध्रिऽअश्व।प्र।वोचन्।यत्।सं
ऽपृच्छं।मानुषीः।विशः।आयन्।त्वां।नृऽभिः।अजयः।त्वाऽवृधेभिः।पिताऽइव।पुत्रं।अबिभः।उप।स्वे।
त्वां।अग्ने।वध्रिऽअश्वः।सपर्यन्।जुषाणः।अस्य।सं।इधे।यविष्ठ।उत।पूर्वान्।अवनोः।व्राधतः।
चित्।शश्वत्।अग्निः।वध्रिऽअश्वस्य।शत्रून्।नृऽभिः।जिगाय।सुतसोमवत्ऽभिः।समनं।चित्।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ दृहः। चित्रभानो इति चित्रऽभानो। अर्वा। ब्राधन्तं। अभिऽनता। रथः। चिता। अयं। अग्निः। वध्रिऽअश्वस्य।
२६ वृत्रऽहा। सनकात्। पऽइद्धः। नमसा। उपऽवाक्यः। सः। नः। अजामीन्। उत। वा। विऽजामीन्। अभि। नि
26 ष्ठा। शर्द्धतः। वाध्रिऽअश्वा। २१॥०। तनूऽपात्। स्वाऽइक्नः। पदे। प्रति। हर्य्यं। घृताचीं। वर्ष्मन्। पृथिव्याः। सुदिनऽत्वे।
अह्नां। ऊर्ध्वः। भव। सुक्रतो इति सुऽक्रतो। देवऽयज्या। आ। देवानां। अप्यऽयाः। इह। यातु। नराशंसः।
त विश्वऽरूपेभिः। अश्वैः। ऋतस्य। पथा। नमसा। मियेधः। देवेभ्यः। देवऽतमः। सुऽस्वदत्। शश्वत्ऽतमं। ईक्ष
ते। दूत्याय। हविष्मंतः। मनुष्यासः। अग्निं। वहिष्ठैः। अश्वैः। सुऽरथो। रथेन। आ। देवान्। वक्षि। नि। सद।
इह। होता। वि। प्रथतां। देवऽजुष्टं। तिरः। भ्रा। दीर्घं। द्राघ्मा। सुरभि। भूतु। अस्मे इति। अहेऽक्रता। मनसा। देव। २६

बर्हिः। इंद्रऽज्येष्ठान्। उशतः। यक्षि। देवान्। दिवः। वा। सानु। स्पृशत। वरीयः। पृथिव्या। वा। मात्रया। वि। श्रयध्वं।
उशतीः। द्वारः। महिना। महत्ऽभिः। देवं। रथं। रथऽयुः। धारयध्वं॥ २३॥ देवी इति। दिवः। दुहितरा। सुशिल्पे इ
ति सुऽशिल्पे। उषसानक्ता। सदतां। नि। योनौ। आ। वां। देवासः। उशती इति। उशंतः। उरौ। सीदंतु। सुभगे इति
सुऽभगे। उपऽस्थे॥ ऊर्ध्वः। ग्रावा। बृहन्। अग्निः। सम्ऽइद्धः। प्रिया। धामानि। अदितेः। उपऽस्थे। पुरःऽहिता। ऋत्वि
जा। यज्ञे। अस्मिन्। विदुःऽतरा। द्रविणं। आ। यजेथां। तिस्रः। देवीः। बर्हिः। इदं। वरीयः। आ। सीदत। चकृम। वः।
स्योनं। मनुष्वत्। यज्ञं। सुऽधिता। हवींषि। इळा। देवी। घृतऽपदी। जुषंत। देवा। त्वष्टः। यत। हा। चारुऽत्वं। आनट्।
यत्। अंगिरसां। अभवः। सचाऽभूः। सः। देवानां। पाथः। उप। प्र। विद्वान्। उशन्। यक्षि। द्रविणःऽदः। सुऽरत्नः।

© Dharmartha Trust J&K. Digitized by eGangotri

१०अ० वनस्पते। रशनया। निऽयूय। देवानां। पाथः। उप। वक्षि। विद्वान्। स्वदाति। देवः। कृणवत्। हवींषि। अवतां। द्या
२८ वापृथिवी इति। हवं। मे। आ। अग्ने। वह। वरुणं। इष्टये। नः। इंद्रं। दिवः। मरुतः। अंतरिक्षात्। सीदंतु। बर्हिः। विश्वे।
आ। यजत्राः। ११। २२। बृहस्पते। प्रथमं। वाचः। अग्रं। यत्। प्र। ऐरत। नामऽधेयं। दधानाः। यत्। एषां। श्रेष्ठं।
27 यत्। अरिप्रं। आसीत्। प्रेणा। तत्। एषां। निऽहितं। गुहा। आविः। सक्तुंऽइव। तितउना। पुनंतः। यत्र। धीराः।
मनसा। वाचं। अक्रत। अत्र। सखायः। सख्यानि। जानते। भद्रा। एषां। लक्ष्मीः। निऽहिता। अधि। वाचि।
यज्ञेन। वाचः। पदऽवीयं। आयन्। तां। अनु। अविंदन्। ऋषिषु। प्रऽविष्टां। तां। आऽभृत्य। वि। अदधुः। पुरुऽ
त्रा। तां। सप्त। रेभाः। अभि। सं। नवंते। उत। त्वः। पश्यन्। न। ददर्श। वाचं। उत। त्वः। श्रृण्वन्। न। श्रृणोति। ए २८

© Dharmartha Trust J&K. Digitized by eGangotri

नां। उतो इति। त्वस्मै। तन्वं। वि। सस्रे। ०। उत। त्वं। सख्ये। स्थिरऽपीतं। आहुः। न। एनं। हिन्वंति। अपि। वाजि
नेषु। अधेन्वा। चरति। मायया। एषः। वाचं। शुश्रुऽवान्। अफलां। अपुष्पां॥ ५॥ यः। तित्याज। सचिऽविदं।
सखायं। न। तस्य। वाचि। अपि। भागः। अस्ति। [illegible] यत्। ईं। शृणोति। अलकं। शृणोति। नहि। प्रऽवे
द। सुऽकृतस्य। पंथां। अक्षण्ऽवंतः। कर्णऽवंतः। सखायः। मनःऽजवेषु। असमाः। बभूवुः। आदघ्नासः। उपऽ
कक्षासः। ऊं इति। त्वे। ह्रदाःऽइव। स्नात्वाः। ऊं इति। त्वे। ददृश्रे। हृदा। तष्टेषु। मनसः। जवेषु। यत्। ब्राह्मणाः। सं
यजंते। सखायः। अत्र। अह। त्वं। वि। जहुः। वेद्याभिः। ओहऽब्रह्माणः। वि। चरंति। ऊं इति। त्वे। इमे। ये। न। अर्वा
क्। न। परः। चरंति। न। ब्राह्मणासः। न। सुतेऽकरासः। ते। एते। वाचं। अभिऽपद्य। पापया। सिरीः। तंत्रं। तन्व

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. ता। अग्रऽजज्ञयः। सर्वे। नंदंति। यशसा। आऽगतेन। सभाऽसहेन। सख्या। सखायः। किल्बिषऽस्पृत्। पितुऽ

२८ सनिः। हि। एषां। अरं। हितः। भवति। वाजिनाय। ऋचां। त्वः। पोषं। आस्ते। पुपुष्वान्। गायत्रं। त्वः। गायति। शा

28 क्करीषु। ब्रह्मा। त्वः। वदति। जातऽविद्यां। यज्ञस्य। मात्रां। वि। मिमीते। ऊं इति। त्वः। ॥२४॥ इति अष्टमाष्टके द्वि

तीयोध्यायः॥ ॐ॥ देवानांनवलौक्योवाबृहस्पतिर्दाक्षायण्यदितिर्वादैवमानुष्टुभं जनिष्ठाएका

दशागोरिवीतिर्वैसूनोंषट्प्रसुनवसिंधुक्षित्प्रैयमेधोनदीस्तुतिर्जांगतं।वावोष्टौसर्पऐरावतोजरत्क

र्णोग्राव्णोस्तौदप्रप्रुष[illegible]मरश्मिर्भार्गवोमारुतंतुपंचमीजगतीविप्रासोद्वितीयापंचम्यापाश्व

तिस्त्रोजगत्योपश्येसप्तसाचीकोग्निर्वैश्वानरोवासप्तिर्वाजंभरआग्नेयंत्वग्निःसप्तिंयद्माविश्वा २८

© Dharmartha Trust J&K. Digitized by eGangotri

विश्वकर्मा भौवनो। वैश्वकर्माणं तु द्वितीया विराड्रूपा। श्वस्तुषो यस्तोमन्यो मन्युस्तापसो मान्यवं त्वा
द्याजगती। स्वया मन्यो चतुर्जगत्यंतं तं सत्येन सप्तचत्वारिंशः। सावित्रीस्सूर्या।त्मदैवतमानुष्टुभं पंचभिः
सोमस्तोत्रं पराभिः स्वविवाहं सप्तदश्या देवान् परया सोमाकौ परया चेद्रमसं परान्नृणां विवाह मंत्रा
आशीःप्रायाः परादेहि लिङ्गेरधूवासः संस्पर्शनिंदार्थे परा यक्ष्मनाशिनी दंपत्योर्नवोनवन्हिस्त्रोत्रं रक्ष
रा१रभ्णामीति द्वे हृदये अश्विनापूषा घोरचक्षुरिति त्रिष्टुभस्तस्रमुरो बृहती पूर्वा परा सिह प्रियमानः प्रजां
जगत्य।गा।अं१म।।देवानां।नु।वयं।जाना।प्र।वो।चाम।।विपन्यया।।उक्थेषु।।शस्यमानेषु।यः।पश्यात्।उ
त्तरे।युगे।।ब्रह्मणःपतिः।।एता।सं।कर्मारः।इव।अधमत्।देवानां।पूर्व्ये।युगे।असतः।सत्।अजायत।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ देवानां। युगे। प्रथमे। तत॥ आशाः। अनु। अजायंत। तत्। उत्तानऽपदः। परि। भूः। जज्ञे। उत्तानऽपदः। भुवः॥
२९ आशाः। अजायंत। अदितेः। दक्षः। अजायत। दक्षात्। ऊं इति। अदितिः। परि॥ अदितिः। हि। अजनिष्ट। द
क्ष। या। दुहिता। तव। तां। देवाः। अनु। अजायंत। भद्राः। अमृतऽबंधवः॥ यत्। देवाः। अदः। सलिले। सु
ऽसंरब्धाः। अतिष्ठत। अत्र। वः। नृत्यतांऽइव। तीव्रः। रेणुः। अप। आयत॥ यत्। देवाः। यतयः। यथा। भुव
नानि। अपिन्वत। अत्र। समुद्रे। आ। गूळ्हं। आ। सूर्यं। अजभर्तन॥ अष्टौ। पुत्रासः। अदितेः। ये। जा
ताः। तन्वः। परि। देवान्। उप। प्र। ऐत्। सप्तऽभिः। परा। मार्तांडं। आस्यत्॥ सप्तऽभिः। पुत्रैः। अदितिः। उ
प। प्र। ऐत्। पूर्व्यं। युगं। प्रऽजायै। मृत्यवे। त्वत्। पुनः। मार्तांडं। आ। अभरत्॥ राजनिष्ठाः। उग्रः। सह २९

29

© Dharmartha Trust J&K. Digitized by eGangotri

सः।तुरायां।मंद्रः।ओजिष्ठः।बकुलऽअभिमानः।अवईन्।इंद्रं।मरुतः।चित्।अत्र।माता।यत्।वीरं।दध
नत्।धनिष्ठा।द्रुहः।निःऽसत्ता।पृशनी।चित्।एवैः।पुरु।शंसेन।वधुः।नः।इंद्रः।अभिरता।ऽइवा।ताम
हाऽपदेन।ध्वांता।तामऽपिवा।तत्।उत्।अरंता।गर्भाः।ऋघा।तो।पादा।प्रायत।जिगासि।अवईन्।वाजाः।
उता।ये।चित्।अत्रा।त्वां।इंद्र।सा।ला।रकाना।सहस्रं।आसन्।दधिषे।अश्विना।आ।वृरस्याः।समना।तू
र्णिः।उपा।या।सि।यज्ञं।आ।ना।सत्या।सख्या।या।वक्षि।वसाव्यां।इंद्रः।धारयः।सहस्रा।अश्विना।शू
रा।ददतुः।मघानि।मंदमानः।ऋतात।अधि।प्रऽजायो।सखिऽभिः।इंद्रः।इषिरेऽभिः।अर्थं।आ।आभिः
हि।मायाः।उप।दस्युं।आ।अगात्।मिहः।प्रा।तम्राः।अव।पत्।तान।मां।सि।३।।सः।नो।मा।ना।चित्।ध्वस

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. यः। नि। अस्मै। अर्वा। अहन्। इंद्रः। उषसः। यथा। अनः। ऋष्वैः। अगच्छः। सखिऽभिः। निऽकामैः। साकं। प्र
३० तिऽस्था। हृद्या। जघंथ। त्वं। जपेयान मुषिं। मखस्युं। दासं। कृण्वा। नः। ऋषयो। विऽमायं। त्वं। चकर्थ।
मनवे। स्योनान्। पथः। देवऽत्रा। अंजसाऽइव। यानान्। त्वं। एतानि। पप्रिषे। वि। नाम। ईशानः। इंद्र।
30 दधिषे। गभस्तौ। अनु। त्वा। देवाः। शवसा। मदंति। उपरिऽबुध्नान्। वनिनः। चकर्थ। चक्रं। यत्। अस्य।
अप्ऽसु। आ। निऽसत्तं। उतो इति। तत्। अस्मै। मधु। इत्। चच्छद्यात्। पृथिव्यां। अतिऽसितं। यत्। ऊधः।
पयः। गोषु। अदधाः। ओषधीषु। अश्वात्। इयाय। इति। यत्। वदंति। ओजसः। जातं। उत। मन्ये। एनं।
मन्योः। इयाय। हर्म्येषु। तस्थौ। यतः। प्रऽजज्ञे। इंद्रः। अस्य। वेद। वयः। सुऽपर्णाः। उप। सेदुः। इंद्रं। प्रियऽ ३०

© Dharmartha Trust J&K. Digitized by eGangotri

मेधाः।ऋषयः।नाधमानाः।अप।ध्वांतं।ऊर्णुहि।पूर्धि।चक्षुः।मुमुग्धि।अस्मान्।निधयाऽइव।बद्धान्।
॥८॥वसूनां।वा।चर्कृषे।इयक्षन्।धिया।वा।यज्ञैः।वा।रोदस्योः।अर्वतः।वा।ये।रयिऽमंतः।सातौ।वनुं।
वा।ये।सुऽश्रवणं।सुऽश्रुतः।धुरिति धुः।हवः।एषां।असुरः।नक्षत।द्यां।श्रवस्यता।मनसा।निंसत।क्षां।
चक्षाणाः।यत्र।सुविताय।देवाः।द्यौः।न।वारेभिः।कृणवंत।स्वैः।इयं।एषां।अमृतानां।गीः।सर्वऽताता।
ये।कृपणंत।रत्नं।धियं।वा।यज्ञं।वा।साधंतः।ते।नः।धांतु।वसव्यं।असामि।आ।तत।ते।इंद्रा।आयवः।
पनंत।अभि।ये।ऊर्वं।गोऽमंतं।तितृत्सान्।सकृत्ऽस्वं।ये।पुरुऽपुत्रां।महीं।सहस्रऽधारां।बृहतीं।दु
दुक्षन्।शचीऽवः।इंद्रं।अवसे।कृणुध्वं।अनानतं।दमयंतं।पृतन्यून्।ऋभुक्षणं।मघऽवानं।सुऽवृक्तिं।

© Dharmartha Trust J&K. Digitized by eGangotri

१अ मर्त्ता।यः।वज्री।नर्यः।पुरुऽक्षुः।यत्।च्यानि।पुरुऽतमः।पुराषाट्।आ।वृत्रऽहा।इंद्रः।नामानि।अप्राः।अचे
३१ तिऽप्रऽसहः।पतिः।तुविष्मान्।यत्।ईं।उश्मसि।कर्तवे।करत्।तत्।।५।।प्र।सु।वः।आपः।महिमानं।उ
त्ऽउ तमं।कारुः।वोचाति।सदने।विवस्वतः।प्र।सप्तऽसप्त।त्रेधा।हि।चक्रमुः।प्र।सृत्वरीणां।अति।सिंधुः
ओजसा।प्र।ते।अरदत्।वरुणः।यातवे।पथः।सिंधो इति।यत्।वाजान्।अभि।अद्रवः।त्वं।भूम्याः।अ
धि।प्रऽवता।यासि।सानुना।यत्।एषां।अग्रं।जगतां।इरज्यसि।दिवि।स्वनः।यतते।भूम्याः।उपरि।
अनंतं।शुष्मं।उत्।इयर्ति।भानुना।अभ्रात्ऽइव।प्र।स्तनयंति।वृष्टयः।सिंधुः।यत्।एति।वृषभः।
न।रोरुवत्।।अभि।त्वा।सिंधो इति।शिशुं।न।मातरः।वाश्राः।अर्षंति।पयसाऽइव।धेनवः।राजाऽइव। ३१
इत्र

© Dharmartha Trust J&K. Digitized by eGangotri

युध्वा । नयुसि । त्वं । इत् । सिचौ । यत् । आसां । अग्रं । प्रऽवतां । इनक्षसि । इमं । मे । गंगे । यमुने । सरस्वति ।
शुतुद्रि । स्तोमं । सचत । परुष्णि । आ । असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जीकीये । शृणुहि । आ ।
सुऽसोमया ॥ ५ ॥ तृष्टऽअमया । प्रथमं । यातवे । संऽजूः । सुऽसर्त्वा । रसया । श्वेत्या । त्या । त्वं । सिंधो इति ।
कुभया । गोऽमतीं । क्रुमुं । मेहत्न्वा । सऽरथं । याभिः । ईयसे । ऋजीती । एनी । रुशती । महिऽत्वा । परि । ज्र
यांसि । भरते । रजांसि । अदब्धा । सिंधुः । अपसां । अपःऽतमा । अश्वा । न । चित्रा । वपुषीऽइव । दर्शता ।
सुऽअश्वा । सिंधुः । सुऽरथा । सुऽवासाः । हिरण्ययी । सुऽकृता । वाजिनीऽवती । ऊर्णाऽवती । युवतिः । सी
लमाऽवती । उत । अधि । वस्ते । सुऽभगा । मधुऽवृधं । सुऽखं । रथं । युयुजे । सिंधुः । अश्विनं । तेन । वाजं ।

© Dharmartha Trust J&K. Digitized by eGangotri

५·अ· सनिषत्त्।अस्मिन्।आजौ।महान्।आहि।अस्य।महिमा।पनस्यते।अर्द्ध्यस्या।स्वऽयशाः।सः।विऽरुक्मान्ः
३२ ।।७।।आ।वः।कं।उसे।ऊर्जौ।विऽउषिषु।इंद्रं।मरुतः।रोदसीइति।अनक्तना।उभेइति।यथा।नः।अहनी
इति।सचाऽभुवा।सदःऽसदः।वरिवस्यात्।तः।उत्ऽभिदा।तत्।ऊंइति।श्रेष्ठं।सवनं।सुनोतन।अत्यः।न।
हस्तऽयतः।अद्रिः।सोनरि।विदत्।आहि।अर्यः।अभिऽभूति।पौंस्यं।महः।राये।चित्।तनुते।यत्।अवतः।।
नत्।इत्।आहि।अस्या।सवनं।विवेः।अपः।यथा।पुरा।मनवे।गातुं।अश्रेत्।गोऽअर्णसि।त्वाष्ट्रे।अश्व
ऽनिर्णिजि।प्रां।इं।अध्वरेषु।अध्वरान्।आशिश्रयुः।अप।हत।रक्षसः।भंगुरऽवतः।स्कभायत।निः।
ऋतिं।सेधत।अमतिं।आ।नः।रयिं।सर्वऽवीरं।सुनोतन।देवऽअव्यं।भरत।श्लोकं।अद्रयः।दिवः।चित्। ३२

© Dharmartha Trust J&K. Digitized by eGangotri

त

आ। वः। अमवत्ऽतरेभ्यः। विऽभ्वना। चित्। आभ्वः ऽतरेभ्यः। वायोः। चित्। आ। सोमरभः ऽतरेभ्यः। अग्नेः।
अर्चु। चित्। पितुकृत्ऽतरेभ्यः॥ २ ॥ भुरंतु। नः। यशसः। सोतु। अंधसः। ग्रावाणः। वाचा। दिविता। दिविऽमता। नरः। यत्र।
दुहते। काम्यं। मधु। आऽघोषयंतः। अभितः। मिथःऽतुरः। सुन्वंति। सोमं। रथिरासः। अद्रयः। निः। अस्य। रसं।
गोऽइषः। दुहंति। ते। दुहंति। कुधःऽउपऽसेचनाय। कं। नरः। हव्या। न। मर्जयंत। आसऽभिः। एन। नरः। सुऽअप
सः। अभवत। न। ये। इंद्राय। सुनुथ। सोमं। अद्रयः। नामं। वीमं। दिव्याय। धाम्ने। वसुऽवस्त्रः। पार्थिवाय। सु वुः।
न्वते॥ ४ ॥ अग्रऽभुवः। न। वाचा। प्रुषा। वसु। हविष्मंतः। न। यज्ञाः। विऽजानुषः। सुऽमारुतं। न। ब्रह्माणं। अर्ह
सेऽगणं। अस्तोषि। एषां। न। शोभसे। श्रियेऽमर्यासः। अंजीन्। अकृण्वत। सुऽमारुतं। न। पूर्वीः। अति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ क्षपः।दिवः।पुत्रासः।एताः।न।येतिरे।आदित्यासः।ते।अक्राः।न।ववृधुः।प्र।ये।दिवः।पृथिव्याः।न।बर्हणा।
३३ त्मना।रिरिचे।अभ्रात्।न।सूर्यः।पाजस्वन्तः।न।वीराः।पनस्यवः।रिशादसः।न।मर्याः।अभिऽद्यवः।यु
33 ष्माकं।बुध्ने।अपां।न।यामनि।विथुर्यति।न।मही।श्रथर्यति।विश्वऽप्सुः।यज्ञः।अर्वाक्।अयं।सु।वः।प्र
यस्वन्तः।न।सत्राचः।आ।गत।यूयं।धूःऽसु।प्रऽयुजः।न।रश्मिऽभिः।ज्योतिष्मन्तः।न।भासा।विऽउष्टिषु।
श्येनासः।न।स्वऽयशसः।रिशादसः।प्रवासः।न।प्रऽसितासः।परिऽप्रुषः।।३०।।प्र।यत्।वहध्वे।मरुतः।प
राकात्।यूयं।महः।संऽवरणस्य।वस्वः।विदानासः।वसवः।राध्यस्य।आरात्।चित्।द्वेषः।सनुतः।युयो
त।यः।उतऽऋचि।यज्ञे।अध्वरेऽस्थाः।मरुत्ऽभ्यः।न।मानुषः।ददाशत्।रेवत्।सः।वयः।दधते।सुऽवीरं। ३३

© Dharmartha Trust J&K. Digitized by eGangotri

तेहियज्ञेषुयज्ञियासऋग्मोः।

सः।देवानां।अपि।गोऽपीथे।अस्तु॥१२॥आदित्येन।नाम्ना।शंऽभविष्ठाः।ते।नः।अवंतु।रथऽतूः।मनीषां।म
हः।च।यामन्।अध्वरे।चकानाः॥१३॥विप्रासः।न।मन्मऽभिः।सुऽआध्यः।देवऽअव्यः।न।यज्ञैः।सुऽअ
प्नसः।राजानः।न।चित्राः।सुऽसंदृशः।क्षितीनां।न।मर्याः।अरेपसः।अग्निः।न।ये।भ्राजसा।रुक्मऽवक्ष
सः।वातासः।न।स्वऽयुजः।सद्यःऽऊतयः।प्रऽज्ञातारः।न।ज्येष्ठाः।सुऽनीतयः।सुऽशर्माणः।न।सोमाः।
ऋतं।यते।वातासः।न।ये।धुनयः।जिगत्नवः।अग्नीनां।न।जिह्वाः।विऽरोकिणः।वर्मणऽवंतः।न।योधाः। न३
शिमीऽवंतः।पितॄणां।न।शंसाः।सुऽरातयः।रथानां।न।ये।अराः।सऽनाभयः।जिगीवांसः।न।शूराः।
अभिऽद्यवः।वरेऽयवः।न।मर्याः।घृतऽप्रुषः।अभिऽस्वर्तारः।अर्कं।न।सुऽस्तुभः।अश्वासः।न।ये।ज्येष्ठा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सः। आशवः। दिधिषवः। न। रथ्यः। सुऽदानवः। आपः। न। निम्नैः। उदऽभिः। जिगत्नवः। विश्वऽरूपाः। अंगिर
३४ सः। न। सामऽभिः॥३२॥ ग्रावाणः। न। सूरयः। सिंधुऽमातरः। आऽदर्दिरासः। अद्रयः। न। विश्वहा। शिशूलाः।
34 न। क्रीळयः। सुऽमातरः। महाऽग्रामः। न। यामन्। उत। त्विषा। उषसां। न। केतवः। अध्वरऽश्रियः। शुभंऽयवः।
न। अंजिऽभिः। वि। अश्वितन्। सिंधवः। न। ययियः। भ्राजत्ऽऋष्टयः। पराऽवतः। न। योजनानि। ममिरे। सुऽभा
गाः। नः। देवाः। कृणुत। सुऽरत्नान्। अस्मान्। स्तोतॄन्। मरुतः। ववृधानाः। गात। सनात्। हि। वः। रत्नऽधेया अधि। स्तोत्रस्य सख्यस्य
नि। संति॥३३॥ अपश्यं। अस्य। महतः। महिऽत्वं। अमर्त्यस्य। मर्त्यासु। विक्षु। नाना। हनू इति। विभृते इति
विऽभृते। सं। भरेते इति। असिन्वती इति। बप्सती इति। भूरि। अत्तः। गुहा। शिरः। निऽहितं। ऋधक्। अक्षी ३४

© Dharmartha Trust J&K. Digitized by eGangotri

इति। अस्मिन्। वना। अग्निः। जिह्वया। वनानि। अत्राणि। अस्मै। पुरुऽत्रा। सं। भरंति। उत्तानऽहस्ताः। नमसा। अधि।
विक्षु। प्र। मातुः। प्रऽतरं। गुह्यं। इच्छन्। कुमारः। न। वीरुधः। सर्पत्। उर्वीः। ससं। न। पक्वं। अविदत्। शुचंतं।
रिरिह्वांसं। रिपः। उपऽस्थे। अंतरिति। तत्। वां। ऋतं। रोदसीइति। प्र। ब्रवीमि। जायमानः। मातरा। गर्भः। अ
त्ति। न। अहं। देवस्य। मर्त्यः। चिकेत। अग्निः। अंग। विऽचेताः। सः। प्रऽचेताः। यः। अस्मै। अन्नं। तृषु। आऽदधा तृ
ति। आज्यैः। घृतैः। जुहोति। पुष्यति। तस्मै। सहस्रं। अक्षऽभिः। वि। चक्षे। अग्ने। विश्वतः। प्रत्यङ्। असि। त्वं।
किं। देवेषु। त्यजः। एनः। चकर्थ। अग्ने। पृच्छामि। नु। त्वां। अविद्वान्। अक्रीळन्। क्रीळन्। हरिः। अत्तवे। अ
दन्। वि। पर्वऽशः। गांऽइव। चकर्त। असिः। विषूचः। अश्वान्। युयुजे। वनेऽजाः। ऋजीतिऽभिः। रशनाभिः।

© Dharmartha Trust J&K. Digitized by eGangotri

१·अ· गृभीतानां । चक्षसे । मित्रः । वसुऽभिः । सुऽजातः । सं । आनृधे । पर्वऽभिः । वावृधानः ॥ ७ ॥ अग्निः । सप्तिं । वा-
३५ जंऽभरं । ददाति । अग्निः । वीरं । श्रुत्यं । कर्मनिःऽस्थां । अग्निः । रोदसी इति । वि । चरत् । संऽअंजन् । अग्निः ।
नारीं । वीरऽकुक्षिं । पुरंऽधिं ॥ अग्नेः । अप्नसः । सं । इत् । अस्तु । भद्रा । अग्निः । मही इति । रोदसी इति । आ । वि-
वेश । अग्निः । एकं । चोदयत् । समत्ऽसु । अग्निः । वृत्राणि । दयते । पुरूणि ॥ अग्निः । ह । त्यं । जरतः । कर्णं । आ-
व । अग्निः । अत्ऽभ्यः । निः । अदहत् । जरूथं । अग्निः । अत्रिं । घर्मे । उरुष्यत् । अंतः । अग्निः । नृऽमेधं । प्रऽज-
या । असृजत् । सं । अग्निः । दात् । द्रविणं । वीरऽपेशाः । अग्निः । ऋषिं । यः । सहस्रा । सनोति । अग्निः । दिवि ।
हव्यं । आ । ततान । अग्नेः । धामानि । विऽभृता । पुरुऽत्रा ॥ अग्निं । उक्थैः । ऋषयः । वि । ह्वयंते । अग्निं । नरः । या- ३५

35

© Dharmartha Trust J&K. Digitized by eGangotri

मग्नि। बाधिता। सः। अग्निं। वयः। अंतरिक्षे। पतंतः। अग्निः। सहस्रा। परि। याति। गोनां। अग्निं। विप्राः। ईळते।
मानुषीः। याः। अग्निं। मनुषः। नहुषः। वि। जाताः। अग्निः। गांधर्वीं। पथ्यां। ऋतस्य। अग्नेः। गव्यूतिः। घृते।
आ। निऽसत्ता। अग्नये। ब्रह्म। ऋभवः। ततक्षुः। अग्निं। महां। अवोचाम। सुऽवृक्तिं। अग्ने। प्र। अव। जरितारं।
यविष्ठ॥ १५॥ यः। इमा। विश्वा। भुवनानि। जुह्वत्। ऋषिः। होता। नि। असीदत्। पिता। नः। सः। आऽशिषा। अग्नेम हिद्रवि णमा यजस्व।
द्रविणं। इछमानः। प्रथमऽछत्। अवरान्। आ। विवेश। किं। स्वित्। आसीत्। अधिऽस्थानं। आऽरंभणं। क-
तमत्। स्वित्। कथा। आसीत्। यतः। भूमिं। जनयन्। विश्वऽकर्मा। वि। द्यां। और्णोत्। महिना। विश्वऽ-
चक्षाः। विश्वतःऽचक्षुः। उत। विश्वतःऽमुखः। विश्वतःऽबाहुः। उत। विश्वतःऽपात्। सं। बाहुऽभ्यां।

© Dharmartha Trust J&K. Digitized by eGangotri

किंस्विद्वनंकउसवृक्षआसयतोद्यावापृथिवीनिष्टतक्षुः।

प॰अ॰ धमेति।सं।पतत्रैः।द्यावाभूमीइति।जनयन्।देवः।एकः॥मनीषिणः।मनसा।पृच्छत।इत्।ऊंइति।तत्।यत्

३६ 36 त्।अधिऽअतिष्ठत्।भुवनानि।धारयन्।या।ते।धामानि।परमाणि।या।अवमा।या।मध्यमा।विश्वऽक

र्मन्।उत।इमा।शिक्ष।सखिऽभ्यः।हविषि।स्वधाऽवः।स्वयं।यजस्व।तन्वं।२ धानः।विश्वऽकर्मन्।हविषा

वर्धानः।स्वयं।यजस्व।पृथिवीं।उत।द्यां।मुह्यंतु।अन्ये।अभितः।जनाः।सः।इह।अस्माकं।मघऽवा।सूरिः।अस्तु

वाचः।पतिं।विश्वऽकर्माणं।ऊतये।मनःऽजुवं।वाजे।अद्य।हुवेम।सः।नः।विश्वानि।हवनानि।जोषत्।वि

श्वऽशंभूः।अवसे।साधुऽकर्मा॥चक्षुषः।पिता।मनसा।हि।धीरः।घृतं।एनेइति।अजनत्।नम्नमा

नेइति।यदा।इत्।अंताः।अदृहंत।पूर्वे।आत्।इत्।द्यावापृथिवीइति।अप्रथेतां।विश्वऽकर्मा।विऽमनाः। ३६

© Dharmartha Trust J&K. Digitized by eGangotri

आत्। विऽहायाः। धाता। विऽधाता। परमा। उत। संऽदृक्। तेषां। इष्टानि। सं। इषा। मदंति। यत्र। सप्तऽऋषीन्।
परः। एकं। आहुः॥ यः। नः। पिता। जनिता। यः। विऽधाता। धामानि। वेद। भुवनानि। विश्वा। यः। देवानां। नामऽ
धाः। एकः। एव। तं। संऽप्रश्नं। भुवना। यंति। अन्या॥ ते। आ। अयजंत। द्रविणं। सं। अस्मै। ऋषयः। पूर्वे। ज
रितारः। न। भूना। असूर्ते। सूर्ते। रजसि। निऽसत्ते। ये। भूतानि। संऽअकृण्वन्। इमानि॥ परः। दिवा। परः।
एना। पृथिव्या। परः। देवेभिः। असुरैः। यत्। अस्ति॥ कं। स्वित्। गर्भं। प्रथमं। दध्रे। आपः। यत्र। देवाः। संऽ
अपश्यंत। विश्वे॥ तं। इत्। ०। संऽअगच्छंत। विश्वे। अजस्य। नाभौ। अधि। एकं। अर्पितं। यस्मिन्। विश्वा
नि। भुवनानि। तस्थुः॥ न। तं। विदाथ। यः। इमा। जजान। अन्यत्। युष्माकं। अंतरं। बभूव॥ नीहारेण। प्रा

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. वेताः । जल्प्याः । च । असुः । तपः । उग्र्यःऽशासः । चरंति ॥ ३७ ॥ यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः ।
३८ ओजः । पुष्यति । विश्वं । आनुषक् । सह्याम । दासं । आर्यं । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता । मन्युः
इंद्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातऽवेदाः । मन्युं । विशः । ईळते । मानुषीः । याः । पाहि । नः । म-
न्यो इति । तपसा । सऽजोषाः । अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अभि-
त्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वं । नः । त्वं । हि । मन्यो इति । अभिभूतिऽओजाः । स्वयंऽभूः ।
भामः । अभिमातिऽसहः । विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि । अभा-
गः । सन् । अप । परा । इतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रऽचेतः । तं । त्वा । मन्यो इति । अक्रतुः । जि- ३८

© Dharmartha Trust J&K. Digitized by eGangotri

हीडः। अहं। स्वान। तन्वः। बलऽदेयाय। मा। आ। इहि। अयं। ते। अस्मि। उप। मा। आ। इहि। अर्वाङ्। प्रतीचीनः। सहु
रे। विश्वऽधायः। मन्यो इति। वज्रिन्। अभि। मां। आ। ववृत्स्व। हनाव। दस्यून्। उत। बोधि। आपेः। अभि। प्र
इहि। दक्षिणतः। भव। मे। अध। वृत्राणि। जंघनाव। भूरि। जुहोमि। ते। धरुणं। मधः। अग्रं। उभौ। उप। अंशु
प्रथमा। पिबाव॥ १८॥ त्वया। मन्यो इति। सऽरथं। आऽरुजन्तः। हर्षमाणासः। धृषिताः। मरुत्वः। तिग्मऽइषवः।
आयुधा। संऽशिशानाः। अभि। प्र। यंतु। नरः। अग्निऽरूपाः। अग्निःऽइव। मन्यो इति। त्विषितः। सहस्व। सेना
ऽनीः। नः। सहुरे। हूतः। एधि। हत्वाय। शत्रून्। वि। भज। स्वः। वेदः। ओजः। मिमानः। वि। मृधः। नुदस्व। सहस्व।
मन्यो इति। अभि। मातिं। अस्मे इति। रुजन्। मृणन्। प्रऽमृणन्। [illegible] प्र। इहि। शत्रून्। उग्रं। ते। पाजः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ नन्नु। आ। रुरुध्मे। वशी। वशं। नयसे। एकऽज। त्वं। एकः। बहूनां। असि। मन्यो इति। ईड्डितः। विशंऽविशं। यु
३८ धये। सं। शिशाधि। अकृत्तऽरुक्। त्वया। युजा। वयं। द्युऽमंतं। घोषं। विऽजयाय। कृण्महे। विजेषऽकृत्।
इंद्रःऽइव। अनवऽब्रवः। अस्माकं। मन्यो इति। अधिऽपाः। भव। इह। प्रियं। ते। नाम। सहुरे। गृणीमसि। ॰
आऽबभूथ। आऽभूत्या। सहऽजाः। वज्र। सायक। सहः। बिभर्षि। अभिऽभूते। उत्ऽतरं। क्रत्वा। नः। मन्यो
इति। सह। मेदी। एधि। महाऽधनस्य। पुरुऽहूत। संऽसृजि। संऽसृष्टं। धनं। उभयं। संऽआकृतं। अस्मोद भ्यं
तां। वरुणः। च। मन्युः। भियं। दधानाः। हृदयेषु। शत्रवः। पराऽजितासः। अप। नि। लयंतां॥ ३॥ सत्येन।
उत्तभिता। भूमिः। सूर्येण। उत्तभिता। द्यौः। ऋतेन। आदित्याः। तिष्ठंति। दिवि। सोमः। अधि। श्रितः। सोमेन। ३८

© Dharmartha Trust J&K. Digitized by eGangotri

आदित्याः।बलिनः।सोमेन।पृथिवी।मही।अथो इति।नक्षत्राणां।एषां।उपऽस्थे।सोमः।आऽहितः।सोमं।
मन्यते।पपिऽवान्।यत्।संऽपिंषंति।ओषधिं।सोमं।यं।ब्रह्माणः।विदुः।न।तस्य।अश्नाति।कः।चन।आ
छत्ऽविधानैः।गुपितः।बार्हतैः।सोम।रक्षितः।ग्राव्णां।इत्।शृण्वन्।तिष्ठसि।न।ते।अश्नाति।पार्थिवः।
यत्।त्वा।देव।प्रऽपिबंति।ततः।आ।प्यायसे।पुनरिति।वायुः।सोमस्य।रक्षिता।समानां।मासः।आऽकृतिः।
॥२०॥रैभी।आसीत्।अनुऽदेयी।नाराशंसी।निऽओचनी।सूर्यायाः।भद्रं।इत्।वासः।गाथया।एति।
परिऽकृतं।चित्तिः।आः।उपऽबर्हणं।चक्षुः।आः।अभिऽअंजनं।द्यौः।भूमिः।कोशः।आसीत्।यत्।अयात्।सू
र्या।पतिं।स्तोमाः।आसन्।प्रतिऽधयः।कुरीरं।छंदः।ओपशः।सूर्यायाः।अश्विना।वरा।अग्निः।आसीत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१०अ॰ पुरःऽगवः। सोमः। वधूऽयुः। अभवत्। अश्विना। आस्तां। उभा। वरा। सूर्यां। यत्। पत्ये। शंसंतीं। मनसा। सवि
३९ ता। अददात्। मनः। अस्याः। अनः। आसीत्। द्यौः। आसीत्। उत। छदिः। शुक्रौ। अनड्वाहौ। आस्तां। ॰गृहं॥ २३॥
39 ऋक्ऽसामाभ्यां। अभिऽहितौ। गावौ। ते। सामनौ। इतः। श्रोत्रं। ते। चक्रेइति। आस्तां। दिवि। पंथाः। चराचरः। शु
चीइति। ते। चक्रेइति। यातः। विऽआनः। अक्षः। आऽहतः। अनः। मनस्मयं। सूर्या। आ। अरोहत्। प्रऽयती।
पतिं। सूर्यायाः। वहतुः। प्र। अगात्। सविता। यं। अवऽसृजत्। अघासु। हन्यंते। गावः। अर्जुन्योः। परि। उ
ह्यते। यत्। अश्विना। पृच्छमानौ। अयातं। त्रिऽचक्रेण। वहतुं। सूर्यायाः। विश्वे। देवाः। अनु। तत्। वां। अजान
न्। पुत्रः। पितरौ। अवृणीत। पूषा। यत्। अयातं। शुभः। पतीइति। वरेऽयं। सूर्यां। उप। क्व। एकं। चक्रं। वां। आ ३९

© Dharmartha Trust J&K. Digitized by eGangotri

सीत्। क्व। देष्ट्राय। तस्थथुः॥ १५॥ द्वे इति। ते इति। चक्रे इति। सूर्ये। ब्रह्माणः। ऋतुऽथा। विदुः। अथ। एकं। चक्रं। यत्।
गुहा। तत्। अद्धातयः। इत्। विदुः। सूर्यायै। देवेभ्यः। मित्राय। वरुणाय। च। ये। भूतस्य। प्रऽचेतसः। इदं। तेभ्यः। अ
करं। नमः। पूर्वं। अपरं। चरतः। मायया। एतौ। शिशू इति। क्रीळंतौ। परि। यातः। अध्वरं। विश्वानि। अन्यः। भुवना।
अभिऽचष्टे। ऋतून्। अन्यः। विऽदधत्। जायते। पुनरिति। नवःऽनवः। भवति। जायमानः। अह्नां। केतुः। उषसां।
एति। अग्रं। भागं। देवेभ्यः। वि। दधाति। आऽयन्। प्र। चंद्रमाः। तिरते। दीर्घं। आयुः। सुऽकिंशुकं। शल्मलिं। वि
श्वऽरूपं। हिरण्यऽवर्णं। सुऽवृतं। सुऽचक्रं। आ। रोह। सूर्ये। अमृतस्य। लोकं। स्योनं। पत्ये। वहतुं। कृणुष्व॥ २०॥
उत्। ईर्ष्व। अतः। पतिऽवती। हि। एषा। विश्वाऽवसुं। नमसा। गीःऽभिः। ईळे। अन्यां। इच्छ। पितृऽसदं। विऽअक्तां। सः

© Dharmartha Trust J&K. Digitized by eGangotri

उदी

प॰अं ते।भागः।जनुषा।तस्य।विद्धि॥विश्वऽवसो इति विश्वऽवसो।नमसा।ईळामहे।त्वा।अन्यां।इच्छ।प्रऽफर्व्यं।
४० सं।जायां।पत्या।सृज॥अनृक्षराः।ऋजवः।संतु।पंथाः।येभिः।सखायः।यंति।नः।वरेऽयं।सं।अर्यमा।सं।
भगः।नः।निनीयात्।सं।जाःऽपत्यं।सुऽयमं।अस्तु।देवाः॥प्र।त्वा।मुंचामि।वरुणस्य।पाशात्।येन।त्वा।
40 अबध्नात्।सविता।सुऽशेवः।ऋतस्य।योनौ।सुऽकृतस्य।लोके।अरिष्टां।त्वा।सह।पत्या।दधामि॥प्र।इतः।
मुंचामि।न।अमुतः।सुऽबद्धां।अमुतः।करं।यथा।इयं।इंद्र।मीढ्वः।सुऽपुत्रा।सुऽभगा।असति॥२४॥पूषा।
त्वा।इतः।नयतु।हस्तऽगृह्य।अश्विना।त्वा।प्र।वहतां।रथेन।गृहान्।गच्छ।गृहऽपत्नी।यथा।असः।वशिनी।
त्वं।विदथं।आ।वदासि॥इह।प्रियं।प्रऽजया।ते।सं।ऋध्यतां।अस्मिन्।गृहे।गार्हऽपत्याय।जागृहि।एना। ४०

© Dharmartha Trust J&K. Digitized by eGangotri

पत्यौ।तन्वं।सं।स्पृशस्व।अथ।जिव्री।इति।विदथं।आ।वदाथः।नीलऽलोहितं।भवति।कृत्या।आसक्तिः।
वि।अज्यते।एधंते।अस्याः।ज्ञातयः।पतिः।बंधेषु।बध्यते।परा।देहि।शामुल्यं।ब्रह्मऽभ्यः।वि।भज।वसु।
कृत्या।एषा।पत्ऽवती।भूत्वी।आ।जाया।विशते।पतिं।अश्रीरा।तनूः।भवति।रुशती।पापया।अमुया।
पतिः।यत्।वध्वः।वाससा।स्वं।अंगं।अभिऽधित्सते।रपा।ये।वध्वः।चंद्रं।वहतुं।यक्ष्माः।यंति।जनात्।
अनु।पुनरिति।तान्।यज्ञियाः।देवाः।नयंतु।यतः।आऽगताः।मा।विदन्।परिऽपंथिनः।ये।आऽसीदं
ति।दंपती इति दंऽपती।सुऽगेभिः।दुःऽगं।अति।इतां।अप।द्रांतु।अरातयः।सुऽमंगलीः।इयं।वधूः।इ
मां।सं।एत।पश्यत।सौभाग्यं।अस्यै।दत्वाय।अथ।अस्तं।वि।परा।इत।तृष्टं।एतत्।कटुकं।एतत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१०अ० अपाष्ठऽवत्।विषऽवत्।न।एतत्।अत्तवे।सूर्या।यः।ब्रह्मा।विद्यात्।सः।इत्।वाधूऽयं।अर्हति।आऽशसनं। सं
४१ विऽशसनं।अथो इति।अधिऽविकर्तनं।सूर्यायाः।पश्य।रूपाणि।तानि।ब्रह्मा।तु।शुंधति।रव।गृभ्णा
मि।ते।सौभगऽत्वाय।हस्तं।मया।पत्या।जरत्ऽअष्टिः।यथा।असः।भगः।अर्यमा।सविता।पुरंऽधिः।म
ह्यं।त्वा।अदुः।गार्हऽपत्याय।देवाः।तां।पूषन्।शिवऽतमां।आ।ईरयस्व।यस्यां।बीजं।मनुष्याः।वपंति।
या।नः।ऊरू इति।उशती।विऽश्रयाते।यस्यां।उशंतः।प्रऽहराम।शेपं।तुभ्यं।अग्रे।परि।अवहन्।सूर्यां।वह
तुना।सह।पुनरिति।पतिऽभ्यः।जायां।दाः।अग्ने।प्रऽजया।सह।पुनरिति।पत्नीं।अग्निः।[illegible]।अदात्।
आयुषा।सह।वर्चसा।दीर्घऽआयुः।अस्याः।यः।पतिः।जीवाति।शरदः।शतं।सोमः।प्रथमः।विविदे।गंध ४१

© Dharmartha Trust J&K. Digitized by eGangotri

म

वः। विविदे। उत्तरः। तृतीयः। अग्निः। ते। पतिः। तुरीयः। ते। मनुष्यऽजाः। ४०। सोमः। ददत्। गंधर्वाय। गंधर्वः। दद

त्। अग्नये। रयिं। च। पुत्रान्। च। अदात्। अग्निः। मह्यं। अथो इति। इमां। इह। एव। स्तं। मा। वि। यौष्टं। विश्वं। आ

युः। वि। अश्नुतं। क्रीळंतौ। पुत्रैः। नप्तृऽभिः। मोदमानौ। स्वे। गृहे। आ। नः। प्रजां। जनयतु। प्रजाऽपतिः। आऽअ

रसाय। सं। अनक्तु। अर्यमा। अदुःऽमंगलीः। पतिऽलोकं। आ। विश। शं। अघोरऽचक्षुः। अपतिऽघ्नी। एधि शंनोभवतु

शिवा। पशुऽभ्यः। सुऽमनाः। सुऽवर्चाः। वीरऽसूः। देवऽकामा। स्योना। ०। इमां। त्वं। इंद्र। मीढ्वः। सुऽपुत्रां शंनोभवतु

सुऽभगां। कृणु। दश। अस्यां। पुत्रान्। आ। धेहि। पतिं। एकादशं। कृधि। संऽराज्ञी। श्वशुरे। भव। संऽराज्ञी।

श्वश्र्वां। भव। ननांदरि। संऽराज्ञी। भव। संऽराज्ञी। अधि। देवृषु। सं। अंजंतु। विश्वे। देवाः। सं। आपः। हृदयानि

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. नि।नौ।सं।मातरिश्वा।सं।पाना।सं।ऊं इति।दद्री।दधातु।नौ।।२८।।इति अष्टमाष्टके तृतीयोध्यायः।। ।।
४२ हरिः ॐ मा।।विहिन्यपिकैंद्रो रषाकपिरिंद्राणीं इश्च समृद्दिरे पां क्तं रक्षोहणं पंचाधिका पायुराग्नेयं त्र
सो घ्नं चतुरनुष्टुब्वं तं हविरेको नांगिरसो मूर्द्धन्वान्वामदेव्यो यासौर्यवैश्वानरीयमिंद्रस्त्व वद्धूनारेणुः पं
चम्यैंद्रासोमी स[illegible] हस्रशीर्षा षोकशनारायणः यो रुषमानुष्टुमं त्रिष्टुबं तं तु संजागरवद्भिः पंचोना
रुणो वैतहव्य आग्नेयं यज्ञस्य शार्या तो मानवो वैश्वदेवं तु नागतं महितान्वः पार्थः प्रस्तार पांक्तै पुरस्ता
द्बृहत्यं तं त्रयोदश्या येचानुष्टुभो नवम्यक्षरैः पंक्तिरेकादशीन्त्यं तु सारिणी प्रैतेषकूना सर्पो र्बुदः का
द्रवेयो ग्राव्णोस्तौ पंचम्यं येत्रिष्टुभौ सप्तमी च।। ॐ मा।।वि।हि।सो।नो।ः अ रक्ष।ता।नो।इंद्रा।देवं।अ।मं ४२

© Dharmartha Trust J&K. Digitized by eGangotri

सता। यत्र। अमदत्। वृषाकपिः। अर्यः। पुष्टेषु। मत्ऽसखा। विश्वस्मात्। इंद्रः। उत्ऽतरः। परा। हि। इंद्र। धा
वसि। वृषाकपेः। अति। व्यथिः। नो इति। अह। प्र। विंदसि। अन्यत्र। सोमऽपीतये ॥ किं। अयं। त्वां। वृषा
कपिः। चकार। हरितः। मृगः। यस्मै। इरस्यसि। इत्। ऊं इति। नु। अर्यः। वा। पुष्टिऽमत्। वसु ॥ यं।
इमं। त्वं। वृषाकपिं। प्रियं। इंद्र। अभिऽरक्षसि। श्वा। नु। अस्य। जंभिषत्। अपि। कर्णे। वराहऽयुः ॥ प्रिया।
तष्टानि। मे। कपिः। विऽअक्ता। वि। अदूदुषत्। शिरः। नु। अस्य। राविषं। न। सुऽगं। दुःऽकृते। भुवं ॥३॥ न। म
त्। स्त्री। सुभसत्ऽतरा। न। सुयाभुऽतरा। भुवत्। न। मत्। प्रतिऽच्यवीयसी। न। सक्थि। उत्ऽयमीय
सी ॥ उवे। अंब। सुलाभिके। यथाऽइव। अंग। भविष्यति। भसत्। मे। अंब। सक्थि। मे। शिरः। मे। विऽइव।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ हृष्यति। ०किं। सुबाहो इति सुऽबाहो। सुऽअंगुरे। पृथुस्तो इति पृथुऽस्तो। पृथुऽजघने। किं। शूरऽपत्नि। नः।
४२ त्वं। अभि। अमीषि। वृषाकपिं। ०अवीरांऽइव। मां। अयं। शराहः। अभि। मन्यते। उत। अहं। अस्मि। वीरि
43 णी। इंद्रऽपत्नी। मरुत्ऽसखा। ०संऽहोत्रं। स्म। पुरा। नारी। समनं। वा। अव। गच्छति। वेधाः। ऋतस्य। वी
रिणी। इंद्रऽपत्नी। महीयते। ०॥ २॥ इंद्राणीं। आसु। नारिषु। सुऽभगां। अहं। अश्रवं। नहि। अस्याः। अपरं। चन।
जरसा। मरते। पतिः। ०न। अहं। इंद्राणि। ररण। सख्युः। वृषाकपेः। ऋते। यस्य। इदं। अप्यं। हविः। प्रियं। दे
वेषु। गच्छति। ०वृषाकपायि। रेवति। सुऽपुत्रे। आत्। ऊं इति। सुऽस्नुषे। घसत्। ते। इंद्रः। उक्षणः। प्रियं। का
चित्ऽकरं। हविः। ०उक्ष्णः। हि। मे। पंचऽदश। साकं। पचंति। विंशतिं। उत। अहं। अद्मि। पीवः। इत्। उभा। ४२

नसेशेरोमं
रांत्र ...॥

कुक्षी इति। पृणंति। मे। ०। वृषभः। न। तिग्मऽशृंगः। अंतः। यूथेषु। रोरुवत्। मंथः। ते। इंद्र। शं। हृदे। यं। ते। सुनो
ति। भावयुः। ०॥ ३॥ न। सः। ईशे। यस्य। रंबते। अंतरा। सक्थ्या। कपृत्। सः। इत्। ईशे। यस्य। रोमशं। निऽसे
दुषः। विऽजृंभते। ०। अयं। इंद्र। वृषाकपिः। परस्वंतं। हतं। विदत्। असिं। सूनां। नवं। चरुं। आत्। एधस्य। अ
नः। आऽचितं। ०। अयं। एमि। विऽचाकशत्। विऽचिन्वन्। दासं। आर्यं। पिबामि। पाकऽसुत्वनः। अभि। धीरं। अ
चाकशं। ०। धन्व। च। यत्। कृंतत्रं। च। कति। स्वित्। ता। वि। योजना। नेदीयसः। वृषाकपे। अस्तं। आ। इहि। गृ
हान्। उप। ०। पुनः। आ। इहि। वृषाकपे। सुविता। कल्पयावहै। यः। एषः। स्वप्नऽनंशनः। अस्तं। एषि। पथा। पुनः।
०। यत्। उदंचः। वृषाकपे। गृहं। इंद्र। अजगंतन। क्वः। स्यः। पुल्वघः। मृगः। कं। अगन्। जनऽयोपनः। ०। पर्शुः। ह।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ नाम।मानवी।साकं।ससूव।विंशतिं।भद्रं।भल।त्यस्यै।अभूत्।यस्याः।उदरं।आमयत्।०।४।रक्षःऽहनं।वा
४४ जिनं।आ।जिघर्मि।मित्रं।प्रथिष्ठं।उप।यामि।शर्म।शिशानः।अग्निः।क्रतुऽभिः।संऽइद्धः।०।अयःऽदंष्ट्रः।
नो अर्चिषा।यातुऽधानान्।उप।स्पृश।जातऽवेदः।संऽइद्धः।आ।जिह्वया।मूरऽदेवान्।रभस्व।क्रव्यऽअदः।वृ
क्त्वी।अपि।धत्स्व।आसन्।उभा।उभयाविन्।उप।धेहि।दंष्ट्रा।हिंस्रः।शिशानः।अवरं।परं।च।उत।
44 अंतरिक्षे।परि।याहि।राजन्।जंभैः।सं।धेहि।अभि।यातुऽधानान्।यज्ञैः।इषूः।संऽनममानः।अग्ने।वा
चा।शल्यान्।अशनिऽभिः।दिहानः।ताभिः।विध्य।हृदये।यातुऽधानान्।प्रतीचः।बाहून्।प्रति।भंग्धि।ए
षां।अग्ने।त्वचं।यातुऽधानस्य।भिंधि।हिंस्रा।अशनिः।हरसा।हंतु।एनं।प्र।पर्वाणि।जातऽवेदः।शृणीहि। ४४

© Dharmartha Trust J&K. Digitized by eGangotri

क्रव्यऽअत्। क्रविष्णुः। वि। चिनोतु। एनं॥५॥ यत्र। इदानीं। पश्यसि। जातऽवेदः। तिष्ठंतं। अग्ने। उत। वा।
चरंतं। यत्। वा। अंतरिक्षे। पथिऽभिः। पतंतं। तं। अस्ता। विध्य। शर्वा। शिशानः॥ उत। आऽलब्धं। स्पृणु
हि। जातऽवेदः। आऽलेभानात्। ऋष्टिऽभिः। यातुऽधानात्। अग्ने। पूर्वः। नि। जहि। शोशुचानः। आमऽ
अदः। क्ष्विंकाः। तं। अदंतु। एनीः। इह। प्र। ब्रूहि। यतमः। सः। अग्ने। यः। यातुऽधानः। यः। इदं। कृणोति।
तं। आ। रभस्व। संऽइधा। यविष्ठ। नृऽचक्षसः। चक्षुषे। रंधय। एनं। तीक्ष्णेन। अग्ने। चक्षुषा। रक्ष।
यज्ञं। प्रांचं। वसुऽभ्यः। प्र। नय। प्रचेत इति प्रऽचेतः। हिंस्रं। रक्षांसि। अभि। शोशुचानं। मा। त्वा। दभन्।
यातुऽधानाः। नृऽचक्षः। नृऽचक्षाः। रक्षः। परि। पश्य। विक्षु। तस्य। त्रीणि। प्रति। शृणीहि। अग्रा। तस्य।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. अग्ने।पृष्टीः।हरसा।शृणीहि।त्रेधा।मूलं।यातुऽधानस्य।वृश्च॥ [illegible]॥त्रिः।यातुऽधानः।प्रऽसितिं।ते।ए
४५ तु।ऋतं।यः।अग्ने।अनृतेन।हन्ति।तं।अर्चिषा।स्फूर्जयन्।जातऽवेदः।संऽअक्षं।एनं।गृणते।नि।वृङ्ग्धि।
४५ तत्।अग्ने।चक्षुः।प्रति।धेहि।रेभे।शफऽआरुजं।येन।पश्यसि।यातुऽधानं।अथर्वऽवत्।ज्योतिषा।
दैव्येन।सत्यं।धूर्वन्तं।अचितं।नि।ओष।यत्।अग्ने।अद्य।मिथुना।शपातः।यत्।वाचः।तृष्टं।जनयन्त।
रेभाः।मन्योः।मनसः।शरव्या।जायते।या।तया।विध्य।हृदये।यातुऽधानान्।परा।शृणीहि।तपसा।
यातुऽधानान्।परा।अग्ने।रक्षः।हरसा।शृणीहि।परा।अर्चिषा।मूरऽदेवान्।शृणीहि।परा।असुऽ
तृपः।अभि।शोशुचानः।परा।अद्य।देवाः।वृजिनं।शृणन्तु।प्रत्यक्।एनं।शपथाः।यन्तु।तृष्टाः।वा ४५

वा॥स्तेनं।शरवः।ऋच्छंतु।मर्मन्।वि।श्वस्य।एतु।प्रऽसितिं।यातुऽधानः॥ऽ॥यः।पौरुषेयेण।क्रविषा।सम्ऽ
अङ्क्ते।यः।अश्व्येन।पशुना।यातुऽधानः।यः।अघ्न्यायाः।भरति।क्षीरं।अग्ने।तेषां।शीर्षाणि।हरसा।
अपि।वृश्च॥संवत्सरीणं।पयः।उस्रियायाः।तस्य।मा।अशीत्।यातुऽधानः।नृऽचक्षः।पीयूषं।अग्ने।
यतमः।तितृप्सात्।तं।प्रत्यंचं।अर्चिषा।विध्य।मर्मन्।विषं।गवां।यातुऽधानाः।पिबंतु।आ।वृश्च्यंतां।
अदितये।दुःऽएवाः।परा।एनान्।देवः।सविता।ददातु।परा।भागं।ओषधीनां।जयंतां।सनात्।अग्ने।मृ
नौ णसि।यातुऽधानान्।न।त्वा।रक्षांसि।पृतनासु।जिग्युः।अनु।दह।सहऽमूरान्।क्रव्यऽदः।मा।ते।हेत्याः।
मुक्षत।दैव्यायाः।त्वं।नः।अग्ने।अधरात्।उदक्तात्।त्वं।पश्चात्।उत।रक्ष।पुरस्तात्।प्रति।ते।ते।अजरा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सः।न।विद्वाः।अपऽशंसं।शोशुचतः।दहंतु।न।पश्चात्।पुरस्तात्।अधरात्।उदक्तात्।कविः।काव्येन।परि।
५८ पाहि।राजन्।सखे।सखायं।अजरः।जरिम्णे।अग्ने।मर्तान्।अमर्त्यः।त्वं।नः।परि।त्वा।अग्ने।पुरं।वयं।
विप्रं।सहस्य।धीमहि।धृषत्ऽवर्णं।दिवेऽदिवे।हंतारं।भंगुरऽवतां।विषेण।भंगुरऽवतः।प्रति।स्म।रक्षसः।
56 दह।अग्ने।तिग्मेन।शोचिषा।तपुःऽअग्राभिः।ऋष्टिऽभिः।प्रति।अग्ने।मिथुना।दह।यातुऽधाना।किमीदि
ना।सं।त्वा।शिशामि।जागृहि।अदब्धं।विप्र।मन्मऽभिः।प्रति।अग्ने।हरसा।हरः।शृणीहि।विश्वतः।प्रति।
यातुऽधानस्य।रक्षसः।बलं।वि।रुज।वीर्यं।।२।हविः।पांतं।अजरं।स्वःऽविदि।दिविऽस्पृशि।आऽहुतं।
जुष्टं।अग्नौ।तस्य।भर्मणे।भुवनाय।देवाः।धर्मणे।कं।स्वधया।पप्रथंत।गीर्णं।भुवने।नमसा।अपऽगू ५८

© Dharmartha Trust J&K. Digitized by eGangotri

ॐहं। आविः। स्वः। अभवत्। जाते। अग्नौ। तस्य। देवाः। पृथिवी। द्यौः। उत। आपः। अरणयन्। ओषधीः। स
ख्ये। अस्य। देवेभिः। नु। इषितः। यज्ञियेभिः। अग्निं। स्तोषाणि। अजरं। बृहंतं। यः। भानुना। पृथिवीं। द्यां।
उत। इमां। आऽततान। रोदसी इति। अंतरिक्षं। यः। होता। आसीत्। प्रथमः। देवऽजुष्टः। यं। संऽआंजन्।
आज्येन। वृणानाः। सः। पतत्रि। इत्वरं। स्थाः। जगत्। यत्। श्वात्रं। अग्निः। अकृणोत्। जातऽवेदाः। यत्।
जातऽवेदः। भुवनस्य। मूर्द्धन्। अतिष्ठः। अग्ने। सह। रोचनेन। तं। त्वा। अहेम। मतिऽभिः। गीःऽभिः। उक्थैः।
सः। यज्ञियः। अभवः। रोदसिप्राः॥१०॥ मूर्द्धा। भुवः। भवति। नक्तं। अग्निः। ततः। सूर्य्यः। जायते। प्रातः।
उतऽयन्। मायां। ऊं इति। नु। यज्ञियानां। एतां। अपः। यत्। तूर्णिः। चरति। प्रऽजानन्। दृशेन्यः। यः। महिना।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ स्वंऽइद्धः। अरोचत। दिविऽयोनिः। विभाऽवा। तस्मिन्। अग्नौ। सूक्तऽवाकेन। देवाः। हविः। विश्वे। आ। अजुहवुः।
५८ तनूऽपाः। सूक्तऽवाकं। प्रथमं। आत्। इत्। अग्निं। आत्। इत्। हविः। अजनयन्त। देवाः। सः। एषां। यज्ञः। अभ-
47 वत्। तनूऽपाः। तं। द्यौः। वेद। तं। पृथिवी। तं। आपः। यं। देवासः। अजनयन्त। अग्निं। यस्मिन्। आ। अजुहवुः।
भुवनानि। विश्वा। सः। अर्चिषा। ऋजुऽयमानः। अतपत्। महिऽत्वा। स्तोमेन। हि। दिवि। देवासः। अग्निं।
अजीजनन्। शक्तिऽभिः। रोदसिऽप्रां। तं। ऊं इति। अकृण्वन्। त्रेधा। भुवे। कं। सः। ओषधीः। पचति। विश्वऽ
रूपाः॥११॥ यदा। इत्। एनं। अदधुः। यज्ञियासः। दिवि। देवाः। सूर्यं। आदितेयं। यदा। चरिष्णू इति। मिथुनौ।
अभूतां। आत्। इत्। प्र। अपश्यन्। भुवनानि। विश्वा। विश्वस्मै। अग्निं। भुवनाय। देवाः। वैश्वानरं। केतुं। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

अन्हां। अकृण्वन्। आ। यः। ततान। उषसः। विऽभातीः। अपो इति। ऊर्णोति। तमः। अर्चिषा। यन्। वैश्वानरं। क
वयः। यज्ञियासः। अग्निं। देवाः। अजनयन्। अजुर्य्यं। नक्षत्रं। प्रत्नं। अमिनत्। चरिष्णु। यक्षस्य। अधिऽअ
क्षं। तविषं। बृहंतं। वैश्वानरं। विश्वहा। दीदिऽवांसं। मंत्रैः। अग्निं। कविं। अछ। वदामः। यः। महिम्ना। परिऽबभू
व। उर्वी इति। उत। अवस्तात्। उत। देवः। परस्तात्। द्वे इति। स्रुती इति। अशृणवं। पितृणां। अहं। देवानां। उत।
मर्त्यानां। ताभ्यां। इदं। विश्वं। एजत्। सं। एति। यत्। अंतरा। पितरं। मातरं। च॥१२॥ द्वे इति। समीची इति। सं
ईची। बिभृतः। चरंतं। शीर्षतः। जातं। मनसा। विऽमृष्टं। सः। प्रत्यङ्। विश्वा। भुवनानि। तस्थौ। अप्रऽयु
छन्। तरणिः। भ्राजमानः। यत्र। वदेते इति। अवरः। परः। च। यज्ञऽन्योः। कतरः। नौ। वि। वेद। आ। शेकुः। इत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१०अ० सधऽमादं । सख्वायः । नक्षंत । यज्ञं । कः । इदं । वि । वोचत् । कति । अग्नयः । कति । सूर्यासः । कति । उषसः । कति । ऊं
८८ इति । स्वित् । आपः । न । उपऽस्पिजं । वः । पितरः । वदामि । पृछामि । वः । कवयः । विद्मने । कं । यावत्ऽमात्रं । उष
सः । न । प्रतीकं । सुऽपर्ण्यः । वसते । मातरिश्वः । तावत् । दधाति । उप । यज्ञं । आऽयन् । ब्राह्मणः । होतुः । अवरः
48 निऽसीदन् । ३३ । इंद्रं । स्तवा । नृऽतमं । यस्य । मन्हा । विऽबबाधे । रोचना । वि । ज्मः । अंतान् । आ । यः । पप्रौ ।
चर्षणिऽधृत् । वरःऽभिः । प्र । सिंधुऽभ्यः । रिरिचानः । महिऽत्वा । सः । सूर्यः । परि । उरु । वरांसि । आ । इंद्रः । ववृ
त्यात् । रथ्याऽइव । चक्रा । अतिष्ठंतं । अपस्यं । न । सर्गं । कृष्णा । तमांसि । त्विष्या । जघान । समानं । अस्मै
। अनपऽवृत् । अर्च । क्ष्मया । दिवः । असमं । ब्रह्म । नव्यं । वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इंद्रः । चिका ८८

© Dharmartha Trust J&K. Digitized by eGangotri

स

या।ना।सरत्वा।यं।ईं।बे।इंद्राय।गिरः।अनिशितऽसर्गाः।अपः।प्र।ईरयं।रगारस्य।बुध्नात्।यः।अक्षेणऽइव।च
क्रिया।शचीभिः।विष्वक्।तस्तंभ।पृथिवीं।उत।द्यां।आपांतऽमन्युः।तृपलऽप्रभर्मा।धुनिः।शिमीऽवान्।रु
शरुःऽमान्।ऋजीषी।सोमः।विश्वानि।अतसा।वनानि।न।अर्वाक्।इंद्रं।प्रतिऽमानानि।देभुः॥४॥न।
यस्य।द्यावापृथिवीइति।न।धन्व।न।अंतरिक्षं।न।अद्रयः।सोमः।अक्षाः।इति।यत्।अस्य।मन्युः।अधिऽनी
यमानः।शृणाति।वीळु।रुजति।स्थिराणि।जघान।वृत्रं।स्वऽधितिः।वनाऽइव।रुरोज।पुरः।अरदत्।न।सिंधू
न्।बिभेद।गिरिं।नवं।इत्।न।कुंभं।आ।गाः।इंद्रः।अकृणुत।स्वयुक्ऽभिः।त्वं।ह।त्यत्।ऋणऽयाः।इंद्र।धीरः।
असिः।न।पर्व।वृजिना।शृणासि।प्र।ये।मित्रस्य।वरुणस्य।धाम।युजं।न।जनाः।मिनंति।मित्रं।प्र।ये।मि

© Dharmartha Trust J&K. Digitized by eGangotri

१·अ· त्रं।प्र।अर्यमणं।दुःऽएवाः।प्र।संऽगिरः।प्र।वरुणं।मिनंति।नि।अमित्रेषु।वधं।इंद्र।तुम्रं।वृषन्।वृषाणं।
४८ अरुषं।शिशीहि।इंद्रः।दिवः।इंद्रः।ईशे।पृथिव्याः।इंद्रः।अपां।इंद्रः।इत्।पर्वतानां।इंद्रः।वृधां।इंद्रः।इत्।
49 मेधिराणां।इंद्रः।क्षेमे।योगे।हव्यः।इंद्रः।।१०।।प्र।अक्तुऽभ्यः।इंद्रः।प्र।वृधः।अहऽभ्यः।प्र।अंतरिक्षात्।प्र।
समुद्रस्य।धासेः।प्र।वातस्य।प्रथसः।प्र।ज्मः।अंतात्।प्र।सिंधुऽभ्यः।रिरिचे।प्र।क्षितिऽभ्यः।प्र।शोशुच
त्याः।उषसः।न।केतुः।असिन्वा।ते।वर्ततां।इंद्र।हेतिः।अश्माऽइव।विध्य।दिवः।आ।सृजानः।तपिष्ठेन।
हेषसा।द्रोघऽमित्रान्।अनु।अह।मासाः।अनु।इत्।वनानि।अनु।ओषधीः।अनु।पर्वतासः।अनु।इंद्रं।
रोदसीइति।वावशानेइति।अनु।आपः।अजिहत।जायमानं।कर्हि।स्वित्।सा।ते।इंद्र।चेत्या।असत्। ४९

© Dharmartha Trust J&K. Digitized by eGangotri

अघस्य। यत्। मिनदः। रक्षः। आऽईवत्। मित्रऽक्रुवः। यत्। शासनेः। न। गावः। पृथिव्याः। आऽपृक्। अमुया।
शयंते। शत्रुऽयंतः। अभि। ये। नः। ततस्रे। महि। व्राधंतः। ओगणाः। सः। इंद्र। अंधेन। अमित्राः। तमसा। स
चंतां। सुऽज्योतिषः। अक्तवः। तान्। अभि। स्युः। इति। स्युः। पुरूणि। हि। त्वा। सवना। जनानां। ब्रह्माणि। मं
दन्। गृणतां। ऋषीणां। इमां। आऽघोषन्। अवसा। सऽहूतिं। तिरः। विश्वान्। अर्चतः। याहि। अर्वाङ्। एव
ते। वयं। इंद्र। भुंजतीनां। विद्याम। सुऽमतीनां। नवानां। विश्वामित्राः॥ ३ सहस्रऽशीर्षा। पुरुषः। स विद्यामुवस्तो
हस्रऽअक्षः। सहस्रऽपात्। सः। भूमिं। विश्वतः। वृत्वा। अति। अतिष्ठत्। दशऽअंगुलं। पुरुषः। एव। इदं।
सर्वं। यत्। भूतं। यत्। च। भव्यं। उत। अमृतऽत्वस्य। ईशानः। यत्। अन्नेन। अतिऽरोहति। एतावान्। अ

© Dharmartha Trust J&K. Digitized by eGangotri

१.अ. स्या। महिमा। अतः। ज्यायान्। च। पुरुषः। पादः। अस्य। विश्वा। भूतानि। त्रिऽपात्। अस्य। अमृतं। दिवि।

५० त्रिऽपात्। ऊर्ध्वः। उत्। ऐत्। पुरुषः। पादः। [illegible] अस्य। इह। अभवत्। पुनरिति। ततः। विष्वङ्। वि। अक्राम

त्। साशनानशने इति। अभि। तस्मात्। विऽराट्। अजायत। विऽराजः। अधि। पुरुषः। सः। जातः। अति।

अरिच्यत। पश्चात्। भूमिं। अथो इति। पुरः। ॥३८॥ यत्। पुरुषेण। हविषा। देवाः। यज्ञं। अतन्वत। वसंतः।

अस्य। आसीत्। आज्यं। ग्रीष्मः। इध्मः। शरत्। हविः। तं। यज्ञं। बर्हिषि। प्र। औक्षन्। पुरुषं। जातं। अग्र

तः। तेन। देवाः। अयजंत। साध्याः। ऋषयः। च। ये। तस्मात्। यज्ञात्। सर्वऽहुतः। संऽभृतं। पृषत्ऽआ

ज्यं। पशून्। तान्। चक्रे। वायव्यान्। आरण्यान्। ग्राम्याः। च। ये। त ऋचः। सामानि। जज्ञिरे। छंदां ५०

© Dharmartha Trust J&K. Digitized by eGangotri

सि। जज्ञिरे। तस्मात्। यजुः। तस्मात्। अजायत। तस्मात्। अश्वाः। अजायन्त। ये। के। च। उभयादतः। गा
वः। ह। जज्ञिरे। तस्मात्। तस्मात्। जाताः। अजावयः॥ इ॥ यत्। पुरुषं। वि। अदधुः। कतिधा। वि। अक
ल्पयन्। मुखं। किं। अस्य। कौ। बाहू इति। कौ। ऊरू इति। पादौ। उच्येते इति। ब्राह्मणः। अस्य। मुखं। आसी
त्। बाहू इति। राजन्यः। कृतः। ऊरू इति। तत्। अस्य। यत्। वैश्यः। पत्ऽभ्यां। शूद्रः। अजायत। चंद्रमाः। मनसः
। जातः। चक्षोः। सूर्यः। अजायत। मुखात्। इंद्रः। च। अग्निः। च। प्राणात्। वायुः। अजायत। नाभ्याः। आसीत्।
अंतरिक्षं। शीर्ष्णः। द्यौः। सं। अवर्तत। पत्ऽभ्यां। भूमिः। दिशः। श्रोत्रात्। तथा। लोकान्। अकल्पयन्। सप्त।
अस्य। आसन्। परिऽधयः। त्रिः। सप्त। संऽइधः। कृताः। देवाः। यत्। यज्ञं। तन्वानाः। अबध्नन्। पुरुषं। पशुं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. यज्ञेन । यज्ञं । अयजंत । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकं । महिमानः । सचंत । य
५१ त्र । पूर्वे । साध्याः । संति । देवाः ॥ १९ ॥ सं । जागृवत्ऽभिः । जरमाणः । इध्यते । दमे । दमूनाः । इषयन् । इळः ।
51 पदे । विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते । सः । दर्शतऽश्रीः ।
अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव । जनंऽजनं । जन्यः । न । अति । मन्यते । विशः ।
आ । क्षेति । विश्यः । विशंऽविशं । सुऽदक्षः । दक्षैः । क्रतुना । असि । सुऽक्रतुः । अग्ने । कविः । काव्येन । असि ।
विश्वऽवित् । वसुः । वसूनां । क्षयसि । त्वं । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः । प्रऽजा
नन् । अग्ने । तव । योनिं । ऋत्वियं । इळायाः । पदे । घृतऽवंतं । आ । असदः । आ । ते । चिकित्रे । उषसांऽ ५१

© Dharmartha Trust J&K. Digitized by eGangotri

इवा। एतयः। अरेपसः। सूर्यस्य ऽइव। रश्मयः। तव। श्रियः। वर्षस्य ऽइव। विऽद्युतः। चित्राः। चिकित्रे। उषसां।
न। केतवः। यत्। ओषधीः। अभिऽसृष्टः। वना। नि। च। परि। स्वयं। चिनुषे। अन्नं। आस्ये॥ २०॥ तं। ओषधीः।
दधिरे। गर्भं। ऋत्वियं। तं। आपः। अग्निं। जनयंत। मातरः। तं। इत्। समाने। वनिनः। च। वीरुधः। अंतःऽवतीः।
च। सुवते। च। विश्वहा। [illegible] वातऽउपधूतः। इषितः। वशान्। अनु। तृषु। यत्। अन्ना। वेविषत्। विऽतिष्ठ
से। आ। ते। यंते। रथ्यः। यथा। पृथक्। शर्धांसि। अग्ने। अजराणि। धक्षतः॥ मेधाऽकारं। विदथस्य। प्रऽसाध
नं। अग्निं। होतारं। परिऽतमं। मतिं। तं। इत्। अर्भे। हविषि। आ। समाने। इत्। तं। इत्। महे। वृणते। न। अन्
यं। त्वत्। यां। इति। अत्र। वृणते। त्वाऽयवः। होतारं। अग्ने। विदथेषु। वेधसः। यत्। देवऽयंतः। दधति। प्रयांसि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.३१. ते। हविष्मंतः। मनवः। वृक्तऽबर्हिषः। ०। २। ॥ ०। मर्त्यैः। सं॑ऽइधा। दाशत्। उत। वा। हविःऽकृति। तस्य। होता। भ

५२ वसि। यासि। दूत्यं। उप। ब्रुषाय। जन्ति। अध्वरि। यासि। इमाः। अस्मै। मतयः। वाचः। अस्मत्। आ। ऋचः।

गिरः। सुऽस्तुतयः। सं। अग्मत। वसुऽयवः। वसवे। जातऽवेदसे। वृद्धासु। चित्। वर्धनः। यासु। चाकनत्।

52 इमां। प्रत्नाय। सुऽस्तुतिं। नवीयसीं। वोचेयं। अस्मै। उशते। शृणोतु। नः। भूयाः। अंतरा। हृदि। अस्य। नि

ऽस्पृशे। ०। यस्मिन्। अश्वासः। ऋषभासः। उक्षणः। वशाः। मेषाः। अवऽसृष्टासः। आऽहुताः। कीलालऽपे।

सोमऽपृष्ठाय। वेधसे। हृदा। मतिं। जनये। चारुं। अग्नये। अहावि। अग्ने। हविः। आस्ये। ते। स्रुचिऽइव। घृ

तं। चम्विऽइव। सोमः। वाजऽसनिं। रयिं। अस्मे इति। सुऽवीरं। प्रऽशस्तं। धेहि। यशसं। बृहंतं। ॥ ३ ॥ यज्ञ ५२

© Dharmartha Trust J&K. Digitized by eGangotri

स्य। वः। रथ्यं। विश्पतिं। विशां। होतारं। अक्तोः। अतिथिं। विभाऽवसुं। शोचन्। शुष्कासु। हरिणीषु। जर्भु-
रत्। वृषा। केतुः। यजतः। द्यां। अशायत। इमं। अंजःऽपां। उभये। अकृण्वत। धर्माणं। अग्निं। विदथस्य।
साधनं। अक्तुं। न। यह्वं। उषसः। पुरःऽहितं। तनूऽनपातं। अरुषस्य। निंसते। वट्। अस्य। नीथा। वि। पणेः।
च। मन्महे। वयाः। अस्य। प्रऽहुताः। आसुः। अत्तवे। यदा। घोरासः। अमृतऽत्वं। आशत। आत्। इत्। ज-
नस्य। दैव्यस्य। चर्किरन्। ऋतस्य। हि। प्रऽसितिः। द्यौः। उरु। व्यचः। नमः। मही। अरमतिः। पनीयसी।
इंद्रः। मित्रः। वरुणः। सं। चिकित्रिरे। अथो इति। भगः। सविता। पूतऽदक्षसः। प्र। रुद्रेण। ययिना। यंति।
सिंधवः। तिरः। महीं। अरमतिं। दधन्विरे। येभिः। परिऽज्मा। परिऽयन्। उरु। ज्रयः। वि। रोरुवत्। जठरे।

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰वैशाः।

प॰अ विश्वै।उक्षतै।।र३।।क्राणाः।रुद्राः।मरुतैः।विश्वऽरूप्यः।दिवः।श्येना।सः।असुरस्य।नीकयेः।तेभिः।
५२ चष्टे।वरुणः।मित्रः।अर्यमा।इंद्रः।देवेभिः।अर्वशेभिः।इंद्रे।भुजे।शशमाना।सः।आशाता।स्तरः।दृशी
के।रथणः।चापौ।स्यो।मायो।नु।अस्या।अहणा।तता।स्विरे।युजे।वज्रो।नःऽस्वदने।षु।कारवः।स्तरः।वि
त्ता।आ।हरितः।अस्या।रीरमत्।इंद्रात्ता।आ।कः।चित्।भयते।तवीयसः।भीमस्य।वृष्णः।जठरात्।अभि
ऽश्वसः।दिवेऽदिवे।सहुरिः।स्तन्।अबाधितः।स्तोमैः।वः।अद्य।रुद्राय।शिक्वसे।क्षयत्ऽवीराय।नमसा।
दिदिष्टन।येभिः।शिवः।स्वऽवान्।एवयावऽभिः।दिवः।सिसक्ति।स्वऽयशाः।निकामऽभिः।ते।हि।प्रऽजा
याः।अभरंत।वि।श्रवः।बृहस्पतिः।वृषभः।सोमऽजामयः।०।विधारयत्।देवाः।दक्षैः।भृगावः।सं।चिक्षि ५२

© Dharmartha Trust J&K. Digitized by eGangotri

नेहिघा वारथिवी

त्रिरे। २४। मूरिडरेलसा। नराशंसः। चतुःऽअंगः। यमः। अदितिः। देवः। त्वष्टा। द्रविणःऽदाः। ऋभुक्षणः। प्र।
रोदसी इति। मरुतः। विष्णुः। अर्हिरे। उता। स्यः। नः। उशिजां। उर्विया। कविः। आहिः। शृणोतु। बुध्न्यः। हवीमनि।
सूर्यामासा। विऽचरंता। दिविऽक्षिता। धिया। शमीनहुषी इति। अस्या। आपतं। प्र। नः। पूषा। चरथं। विश्वऽ
देव्यः। अपां। नपात्। अवतु। वायुः। इषयो। आत्मानं। वस्यः। अभि। वाता। अर्चत। नता। अश्विना। सुऽहवा।
यामनि। श्रुतं। विशां। आसां। अभयानां। अधिऽक्षितं। गीःऽभिः। पुरु इति। स्वऽयशासं। पृणीमसि। ग्नाभिः।
विश्वाभिः। अदितिं। अनर्वणं। अक्तोः। युवानं। नृऽमनाः। अध। पतिं। रेमतां। अत्र। जनुषा। पूर्वः। अंगि
राः। ग्रावाणः। ऊर्ध्वाः। अभि। चक्षुः। अध्वरं। येभिः। विऽहायाः। अभवत्। विऽचक्षणः। पाथः। सुऽमेकं। स्वऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ धितिः। यनन्ऽवति॥२५॥ महि। द्यावा। पृथिवी इति। भूतं। उर्वी इति। नारी इति। यह्वी इति। ना। रोदसी इति।
५४ सदं। नः। तेभिः। नः। पातं। सख्यसः। एभिः। नः। पातं। भूषणि। यज्ञेऽयज्ञे। सः। मर्त्यः। देवान्। सपर्यति। यः।
54 सुम्नैः। दीर्घश्रुत्ऽतमः। आऽविवासाति। एना। नः। विश्वेषां। इरज्यथः। देवानां। वाः। महः। विश्वे। हि। विश्वऽ
महसः। विश्वे। यज्ञेषु। यज्ञियाः। ते। च। राजानः। अमृतस्य। मन्द्राः। अर्यमा। मित्रः। वरुणः। परिऽज्मा। कतुः।
रुद्रः। नृणां। स्तुतः। मरुतः। पूषणं। भगः। उत। नः। नक्तं। अपां। वृषण्वसू इति वृषण्ऽवसू। सूर्यामासा। स
दनाय। सऽधन्या। सचा। यतत्। साधि। एषां। अहिः। बुध्न्येषु। बुध्न्यः॥२६॥ उत। नः। देवौ। अश्विना। शुभः। प
ती इति। धामऽभिः। मित्रावरुणौ। उरुष्यतां॥७॥ अतिः। धन्वऽइव। दुःऽइता। उत। नः। रुद्रा। चित्। मृळतां। अश्विना॥ ५४

© Dharmartha Trust J&K. Digitized by eGangotri

विश्वे।देवासः।रथःपतिः।भगः।ऋभुः।वाजः।ऋभुक्षणः।परिऽज्मा।विश्वऽवेदसः।ऋभुः।ऋभुक्षाः।ऋभुः।
विधतः।मदः।आ।ते।हरी इति।जूजुवानस्य।वाजिना।दुस्तरं।यस्य।साम।चित्।ऋधक्।यज्ञः।न।मानुषः।
रुधि।नः।अह्रयः।देव।सवितरिति।सः।च।स्तुषे।मघोनां।सहो इति।नः।इंद्रः।वह्निऽभिः।नि।एषां।चर्षणीनां।
चक्रं।रश्मिं।न।योयुवे।आ।एषु।द्यावापृथिवी इति।धातं।महत्।अस्मे इति।वीरेषु।विश्वऽचर्षणि।श्रवः।पृक्षं।
वाजस्य।सातये।पृक्षं।राया।उत।तुर्वणे॥ ॥एतं।शंसं।इंद्र।अस्मऽयुः।त्वं।कूऽचित्।संतं।सहसाऽवन्।अभि
ष्टये।सदा।पाहि।अभिष्टये।मेदतां।वेदता।वसो इति।एतं।मे।स्तोमं।तना।न।सूर्ये।द्युतत्ऽयामानं।वावृधंत।
नृणां।संऽवननं।न।अश्व्यं।तष्टाऽइव।अनपऽच्युतं।ववती।येषां।राया।युक्ता।एषां।हिरण्ययी।नेमऽधिता।न।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ यौंस्या। रथाःऽइव। विऽहः। अंता। प्र। तत्। दुःऽशीमे। पृथवाने। वेने। प्र। रामे। वोचं। असुरे। मघवत्ऽसु। ये। यु
५५ क्ताय। पंच। शता। अस्मऽयु। पथा। विऽश्रावि। एषां। अधि। इत्। नु। अत्र। सप्ततिं। च। सप्त। च। सद्यः। दिदिष्ट।
तान्वः। सद्यः। दिदिष्ट। पार्थ्यः। सद्यः। दिदिष्ट। मायवः॥ २८॥ प्र। एते। वदंतु। प्र। वयं। वदाम। ग्रावऽभ्यः। वाचं। व
दत। वदत्ऽभ्यः। यत्। अद्रयः। पर्वताः। साकं। आशवः। श्लोकं। घोषं। भरथ। इंद्राय। सोमिनः। एते। वदंति। श
तऽवत्। सहस्रऽवत्। अभि। क्रंदंति। हरितेभिः। आसऽभिः। विष्ट्वी। ग्रावाणः। सुऽकृतः। सुऽकृत्यया। होतुः। चित्।
पूर्वे। हविःऽअद्यं। आशत। एते। वदंति। अविदन्। अना। मधु। नि। ऊंखयंते। अधि। पक्के। आमिषि। वृक्षस्य।
शाखां। अरुणस्य। बप्सतः। ते। सूऽभर्वाः। वृषभाः। प्र। ईं। अराविषुः। बृहत्। वदंति। मदिरेण। मंदिना। इंद्रं। क्रो ५५

© Dharmartha Trust J&K. Digitized by eGangotri

शंनः।अविदन्।अना।मधु।संऽरभ्या।धीराः।स्वसृऽभिः।अनर्तिषुः।आऽघोषयन्तः।पृथिवीं।उपब्दिऽभिः।सुऽ
पर्णाः।वाचं।अक्रत।उप।द्यवि।आऽखरे।कृष्णाः।इषिराः।अनर्तिषुः।न्यक्।नि।यन्ति।उपरस्य।निःऽकृतं।
पुरु।रेतः।दधिरे।सूर्यऽश्वितः।।२।उग्राः।इव।प्रऽवहन्तः।सम्ऽआयमुः।साकं।युक्ताः।वृषणः।बिभ्रतः।धुरः।
यत्।श्वसन्तः।जग्रसानाः।अराविषुः।शृण्वे।एषां।प्रोथथः।अर्वताऽइव।दशऽअवनिऽभ्यः।दशऽकक्ष्येभ्यः।
दशऽयोक्त्रेभ्यः।दशऽयोजनेभ्यः।दशाभीशुऽभ्यः।अर्चत।अजरेभ्यः।दश।धुरः।दश।युक्ताः।वहत्ऽभ्यः।ते।
अद्रयः।दशऽयन्त्रासः।आशवः।तेषां।आऽधानं।परि।एति।हर्यतं।ते।ऊं इति।सुतस्य।सोम्यस्य।अंधसः।
अंशोः।पीयूषं।प्रथमस्य।भेजिरे।ते।सोमऽअदः।हरी इति।इंद्रस्य।निंसते।अंशुं।दुहन्तः।अधि।आसते।ग

प.अ. श्विा।त्रेभिः। दुग्धां। पपिः। याऽनाः। सोम्यं। मधु। इंद्रः। वर्द्धते। प्रथते। वृषऽयते। वृषा। यः। अंशुः। ना। किल। रिषाथ
५६ ना। इड्वाःऽवंतः। सदां। इत्। स्थन। आशिताः। [stain] रेवत्याःऽइव। महसा। चारवः। स्थन। यस्य। ग्रावाणः। अजु
८ा ष्ध्वं। अध्वरं॥ ११॥ तृदिलाः। अतृदिलासः। अद्रयः। अश्रमणाः। अश्रथिताः। [stain]। अमृत्यवः। अनातुराः। अ
जराः। स्थ। अमविष्णवः। सुऽपीवसः। अतृषिताः। अतृष्णऽजः। ध्रुवाः। एव। वः। पितरः। युगेऽयुगे। क्षेमऽका
मासः। सदसः। न। युंजते। अजुर्यासः। हरिऽसाचः। हरिद्रवः। आ। द्यां। रवेण। पृथिवीं। अशुश्रवुः। न। त्। इत्
नदंति। अद्रयः। विऽमोचने। यामन्। अंजःपाःऽइव। घ। इत्। उपब्दिऽभिः। वपंतः। बीजंऽइव। धान्यऽकृतः।
पृंचंति। सोमं। न। मिनंति। बप्सतः। सुते। अध्वरे। अधि। वाचं। अक्रत। आ। क्रीळयः। न। मातरं। तुदंतः। वि। ५६

© Dharmartha Trust J&K. Digitized by eGangotri

सु।मुंच।सु।सु।सुषः।मनीषां।वि।वर्त्तं।तां।अद्भ्यः।चायमानाः॥३॥इतिअष्टमाष्टके चतुर्थोध्यायः समाप्तः॥
ॐ म॥ हये द्यनोर्वशीमेकः पुरूरवाः पूर्वोविलां कामान्पुनरासा यावरोडुमै छ।सातमस्त्रिछं नीप्र
साचहे हयवड्वुर्याकदास्तुदेवोंतरिक्षप्रांसचेतितिस्वश्चैलयावर्यांशिष्टा३वंश्याः प्रनेसत्तोनावरूः स
र्वहारिवैंद्रोहरिस्तुतिर्हिंत्रिष्टुवंतंयाओषधीस्त्र्यधिकाथर्वणोभिषगोषधिस्तुतिरानुष्टभंबृहस्पले
द्वादशाष्टिषेणोदेवापिर्देष्टिकामोदेवांस्तुष्टावरूंनोयमोवैस्वानसइंद्रुवस्तुवांदनोवैश्वदेवंतुत्रि
ष्टुवंतमुद्रुध्यध्वंबुधःसौम्यत्र्याविकस्तुतिर्वानवम्यंस्येजगत्यौपंचमीबृहतीगायत्र्योमंध्येप्रनेमुद्
लोभामर्व्यश्वोद्रुघणेनत्र्यषभेणचाजिंजिगायेतिद्वौपणंबांपान्तलीयांसाबृहस्यआभ्युःसत्तोनैंद्रो

© Dharmartha Trust J&K. Digitized by eGangotri

प. अ. प्रतिरथश्चतुर्थी बार्हस्पत्यसोपान्त्या द्वादेव्यंस्यानुष्टुमारुतीवासाप्येकादश्याष्टकौ वैश्वामित्रः कद्रा को
५८ सोदुर्मित्रो नाम्नास्सुमित्रो गुणतः सुमित्रो वा नाम्नादुर्मित्रो गुणत औष्णिहं हरीवज्रं पिपीलिकम
ध्ये त्रिष्टुबंत्या द्याणायत्री वा ॥ ॐ मूा हृये। जाये। मनसा। लिष्ठा। घोरा। वचांसि। मिश्रा। रुणवावहै।
नु। न। नौ। मंत्राः। अनुदिताः। सः। एतान्। मयः। करन्। परः। तरे। चन। अहन्। किं। एता। वा। चा। रुणवा। नव।
अहं। श्रा। अक्रमिषं। उषसां। अग्नियाऽइव। उदरूरवः। पुनः। अस्तं। परा। इहि। दुःऽआपना। वातःऽइव। अ
हं। अस्मि। इषुः। न। श्रियेः। इषुऽधेः। असना। गोऽसाः। शतऽसाः। न। रंहिः। अवीरे। क्रतौ। वि। दविद्युतत्।
न। उरा। न। मायुं। चितयंत। धुनयः। सा। वसु। दधती। श्वशुराय। वयः। उषः। यदि। वष्टि। अंतिऽगृहा ५८

© Dharmartha Trust J&K. Digitized by eGangotri

त्।अस्तं।ननक्षे।यस्मिन्।चाकन्।दिवा।नक्तं।श्नथिता।वैतसेन।त्रिः।स्म।मा।अह्नः।श्नथयः।वैतसेन।
उत।स्म।मे।अव्यत्यै।पृणासि।पुरूरवः।अनु।ते।केतं।आयं।राजा।मे।वीर।तन्वः।तत्।आसीः॥४॥या।
सुऽजूर्णिः।श्रेणिः।सुम्नेऽआपिः।ह्रदेऽचक्षुः।न।ग्रंथिनी।चरण्युः।ताः।अंजयः।अरुणयः।न।सस्रुः।श्रि
ये।गावः।न।धेनवः।अनवंत।सं।अस्मिन्।जायमाने।आसत।ग्नाः।उत।ईं।अवर्धन्।नद्यः।स्वऽगूर्ताः।म
हे।यत्।त्वा।पुरूरवः।रणाय।अवर्धयन्।दस्युऽहत्याय।देवाः।सचा।यत्।आसु।अहतीषु।अत्कं।आ।मानु
षीषु।मानुषः।निऽसेवे।अप।स्म।मत्।तरसंती।न।भुज्युः।ताः।अत्रसन्।रथऽस्पृशः।न।अश्वाः।यत्।आ
सु।मर्तः।अमृतासु।निऽस्पृक्।सं।क्षोणीभिः।क्रतुऽभिः।न।पृङ्क्ते।ताः।आतयः।न।तन्वः।शुंभत।स्वाः।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ श्वासः। न। क्रीळयः। दंदशानाः॥ विऽद्युत्। न। या। पतंती। दविद्योत्। भरंती। मे। अप्या। काम्यानि। जनिष्ठो
५८ इति। अपः। नर्यः। सुऽजातः। प्र। उर्वशी। तिरत। दीर्घं। आयुः॥२॥ जज्ञिषे। इत्था। गोऽपीथ्याय। हि। दधाथ।
तत्। पुरूरवः। मे। ओजः। अशासं। त्वा। विदुषी। सस्मिन्। अहन्। न। मे। आ। अशृणोः। किं। अभुक्। वदासि। आ।
कदा। सूनुः। पितरं। जातः। इच्छात्। चक्रन्। न। अश्रु। वर्तयत्। विऽजानन्। कः। दंपती इति दंऽपती। सऽम
नसा। वि। युयोत्। अध। यत्। अग्निः। श्वशुरेषु। दीदयत्। प्रति। ब्रवाणि। वर्तयते। अश्रु। चक्रन्। न। क्रंद
त्। आऽध्ये। शिवायै। प्र। तत्। ते। हिनव। यत्। ते। अस्मे इति। परा। इहि। अस्तं। नहि। मूर। मा। आपः। सुऽदेवः।
अद्य। प्रऽपतेत्। अनाऽवृत्। पराऽवतं। परमां। गंतवै। ऊं इति। अध। शयीत। निःऽऋतेः। उपऽस्थे। अध। एनं। ५८

58

© Dharmartha Trust J&K. Digitized by eGangotri

रकाः। रभसासः। अघुः। उरुरवः। मा। मथाः। मा। ग्नापत्नः। मा। त्वा। वकासः। अशिवासः। ऊं इति। क्षुनराना।
वैः। सैवेणानि। सख्यानि। संनि। सालावृकाणां। हृदयानि। एता॥ आयत्। विरूपा। अचरं। मर्त्येषु। अवसं।
रात्रीः। शरदः। चतस्रः। घृतस्य। स्तोकं। सकृत्। अन्हः। आश्नां। तात्। एव। इदं। ततृपाणा। चरामि। अंतरि
क्षःप्रां। रजसः। विमानीं। उपशिक्षामि। उर्वशीं। वसिष्ठः। उप। त्वा। रातिः। सुकृतस्य। तिष्ठात्। नि। वर्तस्व।
हृदयं। तप्यते। मे। इति। त्वा। देवाः। इमे। आहुः। ऐळ। यथा। ईं। एतत्। भवसि। मृत्युऽबंधुः। प्रऽजा। ते। देवान्। ह
विषा। यजाति। स्वःऽगे। ऊं इति। त्वं। अपि। मादयासे॥ ४॥ प्र। ते। महे। विदथे। शंसिषं। हरीइति। प्र। ते। वन्वे।
वनुषः। हर्यतं। मदं। घृतं। न। यः। हरिऽभिः। चारु। सेचते। आ। त्वा। विशंतु। हरिऽवर्पसं। गिरः। हरिं। हि। योनिं

© Dharmartha Trust J&K. Digitized by eGangotri

१·अ· अभि। ये। संऽअस्वरन्। हिन्वंतः। हरीइति। दिव्यं। यथा। सदः। आ। यं। पृणंति। हरिऽभिः। न। धेनवः। इंद्राय। शू

५९ षं। हरिऽवंतं। अर्चत। सः। अस्य। वज्रः। हरितः। यः। आयसः। हरिः। निऽकामः। हरिः। आ। गभस्त्योः। द्युम्नी। सुऽ

59 शिप्रः। हरिमन्युऽसायकः। इंद्रे। नि। रूपा। हरिता। मिमिक्षिरे। दिवि। न। केतुः। अधि। धायि। हर्यतः। विव्यचत्।

वज्रः। हरितः। न। रंह्या। तुदत्। अहिं। हरिऽशिप्रः। यः। आयसः। सहस्रऽशोकाः। अभवत्। हरिंऽभरः। त्वंऽत्वं। अ

हर्यथाः। उपऽस्तुतः। पूर्वेभिः। इंद्र। हरिऽकेश। यज्वऽभिः। त्वं। हर्य्यसि। तव। विश्वं। उक्थ्यं। असामि। राधः। हरिऽ

जात। हर्य्यतं॥५॥ ता। वज्रिणं। मंदिनं। स्तोम्यं। मदे। इंद्रं। रथे। वहतः। हर्य्यता। हरीइति। पुरूणि। अस्मै। सव

नानि। हर्य्यते। इंद्राय। सोमाः। हरयः। दधन्विरे। अरं। कामाय। हरयः। दधन्विरे। स्थिराय। हिन्वन्। हरयः। ५९

© Dharmartha Trust J&K. Digitized by eGangotri

हरी इति।तुरा।अर्वन्ऽभिः।यः।हरिऽभिः।जोषं।ईयते।सः।अस्य।कामं।हरिऽवंतं।आनशे।हरिऽश्मशारुः।
हरिऽकेशः।आयसः।तुरःऽपेये।यः।हरिऽपाः।अवर्द्धत।वाजिनीऽवसुः।अति।विश्वा।दुःऽइता।पारिषत्।
हरी इति।स्रुवाऽइव।यस्य।हरिणी इति।विऽपेततुः।शिप्रे इति।वाजाय।हरिणी इति।दविध्वतः।प्र।यत्।
कृते।चमसे।ममर्जत्।हरी इति।पीत्वा।मदस्य।हर्यतस्य।अंधसः।उत।स्म।सद्म।हर्य्यतस्य।पस्त्योः।अ
त्यः।न।वाजं।हरिऽवान्।अचिक्रदत्।मही।चित्।धिषणा।अहर्य्यत्।ओजसा।बृहत्।वयः।दधिषे।ह हि।
र्यतः।चित्।आ।।[illegible]।।आ।रोदसी इति।हर्य्यमाणः।महिऽत्वा।नव्यंऽनव्यं।हर्यसि।मन्म।नु।प्रियं।प्र।पस्त्यं।
असुर।हर्यतं।गोः।आविः।कृधि।हरये।सूर्य्याय।आ।त्वा।हर्यतं।प्रऽयुजः।जनानां।रथे।वहंतु।हरिऽशि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ ग्नं। इंद्र। पिब। यथा। प्रतिऽभृतस्य। मध्वः। हर्यन्। यज्ञं। सधऽमादे। दशऽओणिं। अपाः। पूर्वेषां। हरिऽवः। सुता
६० नां। अथो इति। इदं। सवनं। केवलं। ते। ममद्धि। सोमं। मधुऽमंतं। इंद्र। सत्रा। वृषन्। जठरे। आ। वृषस्व॥ ८॥
याः। ओषधीः। पूर्वाः। जाताः। देवेभ्यः। त्रिऽयुगं। पुरा। मनै। नु। बभ्रूणां। अहं। शतं। धामानि। सप्त। च। श
तं। वः। अंब। धामानि। सहस्रं। उत। वः। रुहः। अध। शतऽक्रत्वः। यूयं। इमं। मे। अगदं। कृत। ओषधीः। प्रति।
मोदध्वं। पुष्पऽवतीः। प्रऽसूवरीः। अश्वाःऽइव। सऽजित्वरीः। वीरुधः। पारयिष्ण्वः। ओषधीः। इति। मातरः।
तत्। वः। देवीः। उप। ब्रुवे। सनेयं। अश्वं। गां। वासः। आत्मानं। तव। पूरुष। अश्वत्थे। वः। निऽसदनं। पर्णे।
वः। वसतिः। कृता। गोऽभाजः। इत्। किल। असथ। यत्। सनवथ। पूरुषं॥ ८॥ यत्र। ओषधीः। संऽअग्मत। ६०

60

© Dharmartha Trust J&K. Digitized by eGangotri

राजानः। समितौऽइव। विप्रः। सः। उच्यते। भिषक्। रक्षःऽहा। अमीवऽचातनः। अश्वऽवतीं। सोमऽ
वतीं। ऊर्जयंतीं। उत्ऽओजसं। आ। अवित्सि। सर्वाः। ओषधीः। अस्मै। अरिष्टऽतातये। उत्। शुष्माः।
ओषधीनां। गावः। गोस्थानात्ऽइव। ईरते। धनं। सनिष्यंतीनां। आत्मानं। तव। पुरुष। इष्कृतिः। नाम।
वः। माता। अथो इति। यूयं। स्थ। निःऽकृतीः। सीराः। पतत्रिणीः। स्थन। यत्। आमयति। निः। कृ
थ। अति। विश्वाः। परिऽस्थाः। स्तेनःऽइव। व्रजं। अक्रमुः। ओषधीः। प्र। अचुच्यवुः। यत्। किं। च। तन्
वः। रपः। ता। यत्। इमाः। वाजयन्। अहं। ओषधीः। हस्ते। आऽदधे। आत्मा। यक्ष्मस्य। नश्य
ति। पुरा। जीवऽगृभः। यथा। यस्य। ओषधीः। प्रऽसर्पथ। अंगंऽअंगं। परुःऽपरुः। ततः। यक्ष्मं। वि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ बाधध्वे। उग्रः। मध्यमशीःऽइव। साकं। यक्ष्म। प्र। पत। चाषेण। किकिदीविना। साकं। वातस्य।
६१ ध्राज्या। साकं। नश्य। निऽहाकया। अन्या। वः। अन्यां। अवतु। अन्या। अन्यस्याः। उप। अव
ता। ताः। सर्वाः। संऽविदानाः। इदं। मे। प्र। अवत। वचः। याः। फलिनीः। याः। अफलाः। अपुष्पाः।
याः। च। पुष्पिणीः। बृहस्पतिऽप्रसूताः। ताः। नः। मुंचंतु। अंहसः॥१०॥ मुंचंतु। मा। शपथ्यात्। अ
थो इति। वरुण्यात्। उत। अथो इति। यमस्य। पड्वीशात्। सर्वस्मात्। देवऽकिल्बिषात्। अवऽप
तंतीः। अवदन्। दिवः। ओषधयः। परि। यं। जीवं। अश्नवामहै। न। सः। रिष्याति। पुरुषः। याः।
ओषधीः। सोमऽराज्ञीः। बह्वीः। शतऽविचक्षणाः। तासां। त्वं। असि। उतऽतमा। अरं। कामाय। ६१

© Dharmartha Trust J&K. Digitized by eGangotri

शं। हृदे। ०विऽस्थि ताः। पृथिवीं। अनु। बृहस्पतिऽप्रसूताः। अस्यै। सं। दत्त। वीर्यं। मा। वः। रिषत्। खनि
त्रिता। यस्मै। च। अहं। खनामि। वः। द्विऽपत्। चतुःऽपत्। अस्माकं। सर्वं। अस्तु। अनातुरं। याः। इदं। च
उपऽशृंण्वंति। याः। च। दूरं। पराऽगताः। सर्वाः। संऽगत्य। वीरुधः। ०। ओषधयः। सं। वदंते। सोमे
न। सह। राज्ञा। यस्मै। कृणोति। ब्राह्मणः। तं। राजन्। पारयामसि। त्वं। उत्ऽतमा। असि। ओषधे।
तव। वृक्षाः। उपस्तयः। उपस्तिः। अस्तु। सः। अस्माकं। यः। अस्मान्। अभिऽदासति। ॥११॥ बृह
स्पते। प्रति। मे। देवतां। इहि। मित्रः। [illegible] वा। यत्। वरुणः। वा। असि। पूषा। आदित्यैः। वा। य
त्। वसुऽभिः। मरुत्वान्। सः। पर्यैं। शंऽतनवे। वृषय। आ। देवः। दूतः। अजिरः। चिकित्वान्। त्वत्।
उ

प.अ. देवऽआपे। अभि। मां। अगच्छत्। प्रतीचीनः। प्रति। मां। आ। ववृत्स्व। दधामि। ते। द्युऽमतीं। वाचं। आ
६२ सन्। अस्मे इति। धेहि। द्युऽमतीं। वाचं। आसन्। बृहस्पते। अनमीवां। इषिरां। यया। वृष्टिं। शंऽ
तनवे। वनाव। दिवः। द्रप्सः। मधुऽमान्। आ। विवेश। आ। नः। द्रप्साः। मधुऽमंतः। विशंतु। इंद्र। दे
हि। अधिऽरथं। सहस्रं। नि। सीद। होत्रं। ऋतुऽथा। यजस्व। देवान्। देवऽआपे। हविषा। सपर्य।
आर्ष्टिषेणः। होत्रं। ऋषिः। निऽसीदन्। देवऽआपिः। देवऽसुमतिं। चिकित्वान्। सः। उत्ऽतरस्मात्।
अधरं। समुद्रं। अपः। दिव्याः। असृजत्। वर्ष्याः। अभि। अस्मिन्। समुद्रे। अधि। उत्ऽतरस्मि
न्। आपः। देवेभिः। निऽवृताः। अतिष्ठन्। ताः। अद्रवन्। आर्ष्टिषेणेन। सृष्टाः। देवऽआपिना। ६२

© Dharmartha Trust J&K. Digitized by eGangotri

प्रऽइषिताः। मृक्षिणीषु ॥१२॥ यत्। देवऽआपिः। शंऽतनवे। पुरःऽहितः। होत्राय। वृतः। कृपयन्। अदी
धेत्। देवऽश्रुतं। वृष्टिऽवनिं। ररोणः। बृहस्पतिः। वाचं। अस्मै। अयच्छत्। यं। त्वा। देवऽआपिः। शुशु
चानः। अग्ने। आर्ष्टिषेणः। मनुष्यः। संऽईधे। विश्वेभिः। देवैः। अनुऽमद्यमानः। प्र। पर्जन्यं। ईरय।
वृष्टिऽमन्तं। त्वां। पूर्वे। ऋषयः। गीःऽभिः। आयन्। त्वां। अध्वरेषु। पुरुऽहूत। विश्वे। सहस्राणि। अ
धिऽरथानि। अस्मे इति। आ। नः। यज्ञं। रोहित्ऽअश्व। उप। याहि। एतानि। अग्ने। नवतिः। नव।
त्वे इति। आऽहुतानि। अधिऽरथा। सहस्रा। तेभिः। वर्धस्व। तन्वः। शूर। पूर्वीः। दिवः। नः। वृष्टिं। इ
षितः। रिरीहि। एतानि। अग्ने। नवतिं। सहस्रा। सं। प्र। यच्छ। वृष्णे। इंद्राय। भागं। विद्वान्। पथः।

© Dharmartha Trust J&K. Digitized by eGangotri

१. अ. क्रतुऽशः। देवऽयानान्। अपि। ओत्मानं। दिवि। देवेषु। धेहि। अग्ने। बाधस्व। वि। मृधः। वि। दुःऽ
६३ गहा। अप। अमीवां। अप। रक्षांसि। सेध। अस्मात्। समुद्रात्। बृहतः। दिवः। नः। अपां। भूमा
67 नं। उप। नः। सृज। इह। २३। कं। नः। चित्रं। इषण्यसि। चिकित्वान्। पृथुऽग्मानं। वाश्रं। वृधध्यै।
कत्। तस्य। दातु। शवसः। विऽउष्टौ। तक्षत्। वज्रं। वृत्रऽतुरं। अपिन्वत्। सः। हि। घृणा। विऽद्युता। वेति।
साम। पृथुं। योनिं। असुरऽत्वा। आ। ससाद। सः। सऽनीळेभिः। प्रऽसहानः। अस्य। भ्रातुः। न। ऋ
ते। सप्तथस्य। मायाः। सः। वाजं। याता। अपदुःऽपदा। यन्। स्वःऽसाता। परि। सदत्। सनिष्यन्। अ
नर्वा। यत्। शतऽदुरस्य। वेदः। घ्नन्। शिश्नऽदेवान्। अभि। वर्पसा। भूत्। सः। यह्व्यः। अवनीः। गो ६३

© Dharmartha Trust J&K. Digitized by eGangotri

षु। अवीं। आ। जुहोति। प्रऽधन्या। सु। सस्रिः। अपादः। यत्रा। युऽज्यासः। अरथाः। द्रोणिऽअश्वासः।
ईरते। घृतं। वारिति वाः। सः। रुद्रेभिः। अशस्तऽवारः। ऋभ्वा। हित्वी। गयं। आरेऽअवद्यः। आ। अगात्। आ।
वम्रस्य। मन्ये। मिथुना। विवव्री इति विऽवव्री। अन्नं। अभिऽइत्य। अरोदयत्। मुषायन्। सः। इत्।
दासं। तुविऽरवं। पतिः। दन्। षट्ऽअक्षं। त्रिऽशीर्षाणं। दमन्यत्। अस्य। त्रितः। नु। ओजसा। वृधा
नः। विपा। वराहं। अयःऽअग्रया। हंनिति हन्॥३४॥ सः। द्रुह्वणे। मनुषे। ऊर्ध्वऽसानः। आ। साविष
त्। अर्शसानाय। शरुं। सः। नृऽतमः। नहुषः। अस्मत्। सुऽजातः। पुरः। अभिनत्। अर्हन्। दस्युऽ
हत्ये। सः। अभ्रियः। नायवसो। उदन्यन्। क्षयाय। गातुं। विदत्। नः। अस्मे इति। उप। यन्। आसीदत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ इंद्रं। शरीरैः। श्येनः। अयः। अपाष्टिः। हंति। दस्यून्। सः। व्राधतः। शवसानेभिः। अस्य। कुत्साय। शु
६४ ष्णं। कृपणे। परा। अदात्। अयं। कविं। अनयत्। शस्यमानं। अत्कं। यः। अस्य। सनिता। उत। नृ
65 णां। अयं। दाशस्यन्। नर्येभिः। अस्य। दस्मः। देवेभिः। वरुणः। न। मायी। अयं। कनीनः। ऋतुऽपाः।
अवेदि। अमिमीत। अररुं। यः। चतुःऽपात्। अस्य। स्तोमेभिः। औशिजः। ऋजिश्वा। व्रजं। दर
यत्। वृषभेण। पिप्रोः। सुत्वा। यत्। यजतः। दीदयत्। गीः। पुरः। इयानः। अभि। वर्पसा। भूत्। ए
वा। महः। असुर। वक्षथाय। वम्रकः। पट्ऽभिः। उप। सर्पत्। इंद्रं। सः। इयानः। करति। स्वस्तिं। अ
स्मै। [illegible]। ३५॥ इंद्र। दृह्य। मघऽवन्। त्वाऽवत्। इत्। भुजे। इह। स्तुतः। सुतऽपाः। बोधि। नः। वृधे। ६४

© Dharmartha Trust J&K. Digitized by eGangotri

देवेभिः। नः। सविता। प्र। अवतु। श्रुतं। आ। सर्वऽतातिं। अदितिं। वृणीमहे। भरांया। सु। भरता। भागं।
ऋऽत्वियं। प्र। वायवे। शुचिऽपे। क्रंदतऽइष्टये। गोरस्यां। यः। पयसः। पीतिं। आनशे॥०॥ आ। नः। देव।
सविता। सा। विषत्। वयः। ऋजुऽयते। यजमानाय। सुन्वते। यथा। देवान्। प्रतिऽभूषेम। पाकऽव
ता॥०॥ इंद्रः। अस्मे। इति। सुऽमनाः। अस्तु। विश्वहा। राजा। सोमः। सुवितस्य। अधि। एतु। नः। यथा
ऽयथा। मित्रऽधितानि। संऽदधुः॥०॥ इंद्रः। उक्थेन। शवसा। परुः। दधे। बृहस्पते। प्रऽतरीता। अ त
असि। आयुषः। यज्ञः। मनुः। प्रऽमतिः। नः। पिता। हि। कं॥०॥ इंद्रस्य। नु। सुऽकृतं। दैव्यं। सहः। अ
ग्निः। गृहे। जरिता। मेधिरः। कविः। यज्ञः। च। भूत्। विदथे। चारुः। अंतमः॥०॥१६॥ न। वः। गुहा।

© Dharmartha Trust J&K. Digitized by eGangotri

प·अ· चकृमा।भूरि।दुःऽकृतं।न।आविः।अस्त्यं।वसवः।देवऽहेळनं।मा।किः।नः।देवाः।अनृतस्य।वर्पसः॥०॥
६५ अप।अमीवां।सविता।साविषत्।न्यक्।वरीयः।इत्।अप।सेधंतु।अद्रयः॥०॥ऊर्ध्वः।ग्रावा।
वसवः।अस्तु।सोतरि।विश्वा।द्वेषांसि।सनुतः।युयोत।सः।नः।देवः।सविता।पायुः।ईड्यः॥०॥
ऊर्जं।गावः।यवसे।पीवः।अत्तन।ऋतस्य।याः।सदने।कोशे।अंग्ध्वे।तनूः।एव।तन्वः।अस्तु।भे
षजं॥०॥क्रतुऽप्रावा।जरिता।शश्वतां।अवः।इंद्रः।इत्।भद्रा।प्रऽमतिः।सुतऽवतां।पूर्णं।ऊधः।
दिव्यं।यस्य।सिक्तये॥०॥चित्रः।ते।भानुः।क्रतुऽप्राः।अभिष्टिः।संति।स्पृधः।जरणिऽप्राः।अ
धृष्टाः।रजिष्ठया।रज्या।पश्वः।आ।गोः।तूतूर्षति।परि।अग्रं।दुवस्युः॥६॥उत्।बुध्यध्वं। ६५

© Dharmartha Trust J&K. Digitized by eGangotri

संऽमनसः । सखायः । सं । अग्निं । इंध्वं । बहवः । सऽनीळाः ।०। इंद्रऽवतः । अवसे । नि । ह्वये । वः । मंद्रा ।
कृणुध्वं । धियः । आ । तनुध्वं । नावं । अरित्रऽपरणीं । कृणुध्वं । इष्कृणुध्वं । आयुधा । अरं । कृणुध्वं ।
प्रांचं । यज्ञं । प्र । नयत । सखायः । युनक्त । सीरा । वि । युगा । तनुध्वं । कृते । योनौ । वपत । इह । बीजं ।
गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वं । इयात् । सीरा । युंजंति । कव आ।
यः । युगा । वि । तन्वते । पृथक् । धीराः । देवेषु । सुम्नऽया । निः । आऽहावान् । कृणोतन । सं । वरत्राः ।
दधातन । सिंचामहै । अवतं । उद्रिणं । वयं । सुऽसेकं । अनुपऽक्षितं । इष्कृतऽआहावं । अवतं । सुऽव
रत्रं । सुऽसेचनं । उद्रिणं । सिंचे । अक्षितं ॥ १८ ॥ प्रीणीत । अश्वान् । हितं । जयाथ । स्वस्तिऽवाहं । रथं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ इत्वा।कृणुध्वं।द्रोणऽआहावं।अवतं।अश्मऽचक्रं।अंसत्रऽकोशं।सिंचत।नृऽपानं।व्रजं।कृणुध्वं।सः।
६६ हि।वः।नृऽपानः।वर्म।सीव्यध्वं।बहुला।पृथूनि।पुरः।कृणुध्वं।आयसीः।अधृष्टाः।मा।वः।सुस्रो
त्।चमसः।दृंहत।तं।आ।वः।धियं।यज्ञियां।वर्ते।ऊतये।देवाः।देवीं।यजतां।यज्ञियां।इह।आ।तु।
सिंच।हरिं।ईं।द्रोः।उपऽस्थे।वाशीभिः।तक्षत।अश्मन्ऽमयीभिः।परि।स्वजध्वं।दश।कक्ष्याभिः।उ
भे इति।धुरौ।प्रति।वह्निं।युनक्त।उभे इति।धुरौ।वह्निः।आऽपिब्दमानः।अंतः।योनाऽइव।चरति।
द्विऽजानिः।वनस्पतिं।वने।आ।अस्थापयध्वं।नि।सु।दधिध्वं।अखनंतः।उत्सं।कपृत्।नरः।क
पृथं।उत्।दधातन।चोदयत।खुदत।वाजऽसातये।निःऽटिग्न्यः।पुत्रं।आ।च्यवय।ऊतये।इंद्रं।सः ६६

© Dharmartha Trust J&K. Digitized by eGangotri

बाधः । इह । सोमऽपीतये ॥ १२ ॥ प्र । ते । रथं । मिथुऽकृतं । इंद्रः । अवतु । धृष्णुऽया । अस्मिन् । आजौ ।
पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव । उत । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथं । य
त् । अजयत् । सहस्रं । रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतं । वि । अचेत् । इंद्रऽसेना । अंतः ।
यच्छ । जिघांसतः । वज्रं । इंद्र । अभिऽदासतः । दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय ।
वधं । उद्नः । ह्रदं । अपिबत् । जर्हृषाणः । कूटं । स्म । तृंहत् । अभिऽमातिं । एति । प्र । मुष्कऽभारः । श्रवः । इछ
मानः । अजिरं । बाहू इति । अभरत् । सिसासन् । नि । अक्रंदयन् । उपऽयंतः । एनं । अमेहयन् । वृ
षभं । मध्ये । आजेः । तेन । सूभर्वं । शतऽवत् । सहस्रं । गवां । मुद्गलः । प्रऽधने । जिगाय । ककर्दवे । वृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी । दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छं-
६७ ति । स्म । निःऽपदः । मुद्गलानीं ॥ ६ ॥ उत । प्रऽधिं । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगं । अ-
त्र । शिक्षन् । इंद्रः । उत् । आवत् । पतिं । अघ्न्यानां । अरंहत । पद्याभिः । ककुत्ऽमान् । शुनं । अष्ट्राऽवी ।
अचरत् । कपर्दी । वरत्रायां । दारु । आऽनह्यमानः । नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्प-
शानः । तविषीः । अधत्त । इमं । तं । पश्य । वृषभस्य । युंजं । काष्ठायाः । मध्ये । द्रुऽघनं । शयानं । येन । जि-
गाय । शतऽवत् । सहस्रं । गवां । मुद्गलः । पृतनाऽज्येषु । आरे । अघा । कः । नु । इत्था । ददर्श । यं । युंजंति ।
तं । ऊं इति । आ । स्थापयंति । न । अस्मै । तृणं । न । उदकं । आ । भरंति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् । ६७

© Dharmartha Trust J&K. Digitized by eGangotri

परिऽवृक्ताऽइव।पतिऽविद्यं।आनट्।पीव्याना।कूचक्रेणऽइव।सिंचन्।एषऽएष्या।चित्।रथ्या।
जयेम।सुऽमंगलं।सिनं।वत्।अस्तु।सालं।खं।विश्वस्य।जगतः।चक्षुः।इंद्र।असि।चक्षुषः।
वृषा।यत्।आजिं।वृषणा।सिसाससि।चोदयन्।वध्रिणा।युजा।।२३।।आशुः।शिशानः।वृ
षभः।न।भीमः।घनाघनः।क्षोभणः।चर्षणीनां।संऽक्रंदनः।अनिऽमिषः।एकऽवीरः।शतं।सेनाः
उअजयत्।साकं।इंद्रः।संऽक्रंदनेन।अनिऽमिषेण।जिष्णुना।युत्ऽकारेण।दुःऽच्यवनेन।धृष्णु
ना।तत्।इंद्रेण।जयत।तत्।सहध्वं।युधः।नरः।इषुऽहस्तेन।वृष्णा।सः।इषुऽहस्तैः।सः।निषं
गिऽभिः।वशी।संऽस्रष्टा।सः।युधः।इंद्रः।गणेन।संसृष्टऽजित्।सोमऽपाः।बाहुऽशर्द्धी।उग्रऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ धन्वा। प्रतिऽहिताभिः। अस्ता। बृहस्पते। परि। दीय। रथेन। रक्षःऽहा। अमित्रान्। अपऽबाधमा
६८ नः। प्रऽभंजन्। सेनाः। प्रऽमृणः। युधा। जयन्। अस्माकं। एधि। अविता। रथानां। बलऽविज्ञायः। स्थ
विरः। प्रऽवीरः। सहस्वान्। वाजी। सहमानः। उग्रः। अभिऽवीरः। अभिऽसत्वा। सहःऽजाः। जैत्रं। इं
द्र। रथं। आ। तिष्ठ। गोऽवित्। गोत्रऽभिदं। गोऽविदं। वज्रऽबाहुं। जयंतं। अज्म। प्रऽमृणंतं। ओजसा।
इमं। सऽजाताः। अनु। वीरयध्वं। इंद्रं। सखायः। अनु। सं। रभध्वं। ॥ २२ ॥ अभि। गोत्राणि। सहसा।
गाहमानः। अदयः। वीरः। शतऽमन्युः। इंद्रः। दुःऽच्यवनः। पृतनाषाट्। अयुध्यः। अस्माकं। सेनाः।
अवतु। प्र। युत्ऽसु। इंद्रः। आसां। नेता। बृहस्पतिः। दक्षिणा। यज्ञः। पुरः। एतु। सोमः। देवऽसेनानां। ६८

© Dharmartha Trust J&K. Digitized by eGangotri

अभिःसंजतीनां।जयंतीनां।मरुतः।यंतु।अग्रं।इंद्रस्य।वृष्णः।वरुणस्य।राज्ञः।आदित्यानां।मरुतां।
शर्द्धः।उग्रं।महाऽमनसां।भुवनऽच्यवानां।घोषः।देवानां।जयतां।उत्।अस्थात्।उत्।हर्षय।मघऽ
वन्।आयुधानि।उत्।सत्वनां।मामकानां।मनांसि।उत्।वृत्रऽहन्।वाजिनां।वाजिनानि।उत्।र
थानां।जयतां।यंतु।घोषाः।अस्माकं।इंद्रः।संऽऋतेषु।ध्वजेषु।अस्माकं।याः।इषवः।ताः।जयंतु।अ
स्माकं।वीराः।उत्ऽतरे।भवंतु।अस्मान्।ऊं इति।देवाः।अवत।हवेषु।अमीषां।चित्तं।प्रतिऽलोभयं
ती।गृहाण।अंगानि।अप्वे।परा।इहि।अभि।प्र।इहि।निः।दह।हृत्ऽसु।शोकैः।०।प्र।इत।जयत।
नरः।इंद्रः।वः।शर्म।यछतु।उग्राः।वः।संतु।बाहवः।अनाधष्याः।यथा।असथ॥२३॥असौ।वि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सोमः। पुरःऽऋता। तुभ्यं। हरिऽभ्यां। यज्ञं। उप। याहि। तूयं। तुभ्यं। गिरः। विप्रऽवीराः। इयानाः। दध

६९ न्विरे। इंद्र। पिब। सुतस्य। अपऽसु। धूतस्य। हरिऽवः। पिब। इह। नृऽभिः। सुतस्य। जठरं। पृणस्व

69 ।मिमिक्षुः। यं। अद्रयः। इंद्र। तुभ्यं। तेभिः। वर्धस्व। मदं। उक्थऽवाहः। प्र। उग्रां। प्रीतिं। वृष्णे। इय

र्मि। सत्यां। प्रऽयै। सुतस्य॥ हरिऽअश्व। तुभ्यं। इंद्र। धेनाभिः। इह। मादयस्व। धीभिः। विश्वा

भिः। शच्यां। [illegible]। गृणानः। ऊती। शचीऽवः। तव। वीर्येण। वयः। दधानाः। उशिजः। ऋतऽज्ञाः। प्र

जाऽवंत। इंद्र। मनुषः। दुरोणे। तस्थुः। गृणंतः। सधऽमाद्यासः। प्रनीतिऽभिः। ते। हरिऽअश्व।

सुऽस्तोः। सुऽसुम्नस्य। पुरुऽरुचः। जनासः। मंहिष्ठां। ऊतिं। विऽतिरे। दधानाः। स्तोतारः। इंद्र। ६९

© Dharmartha Trust J&K. Digitized by eGangotri

तवोऽस्तूननाभिः॥२४॥३॥ उप॥ ब्रह्माणि॥ हरिऽवः॥ हरिऽभ्यां॥ सोमस्य॥ याहि॥ पीतये॥ सुतस्य॥ इंद्र॥
त्वा॥ यज्ञः॥ क्षमर्माणं॥ आ॥ नट्॥ दाश्वान्॥ अस्ति॥ अध्वरस्य॥ प्रऽकेतः॥ सहस्रऽवाजं॥ अभिमा
तिऽसहं॥ सुतेऽरणं॥ मघऽवानं॥ सुऽवृक्तिं॥ उप॥ भूषंति॥ गिरः॥ अप्रतिऽइतं॥ इंद्रं॥ नमस्याः॥ ज
रितुः॥ पनंत॥ सप्त॥ आपः॥ देवीः॥ सुऽरणाः॥ अमर्क्ताः॥ याभिः॥ सिंधुं॥ अतरः॥ इंद्र॥ पूःऽभित्॥ न
वतिं॥ स्रोत्याः॥ नव॥ च॥ स्रवंतीः॥ देवेभ्यः॥ गातुं॥ मनुषे॥ च॥ विंदः॥ अपः॥ महीः॥ अभिऽशस्तेः॥ अ
मुंचः॥ अजोगाः॥ आसु॥ अधि॥ देवः॥ एकः॥ इंद्र॥ याः॥ त्वं॥ वृत्रऽतूर्ये॥ चकर्थ॥ ताभिः॥ विश्वऽआयुः॥ त ऽओ
व्वं॥ पुपुष्याः॥ वीरेण्यः॥ क्रतुः॥ इंद्रः॥ सुऽशस्तिः॥ उत॥ अपि॥ धेना॥ पुरुऽहूतं॥ ईट्टे॥ आर्दयत॥ वृत्रं॥ अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ हृणोत्। उँ इति। ओकं। सऽसहः। शक्रः। पृतनाः। अभिऽस्थितिः॥ ण॥ रथ्या। कदा। वसो इति। स्तोत्रं। हर्यते।
७० आ। अव। श्मशा। रुधत्। वाः। इति। वाः। दीर्घं। सुतं। वाताप्याय। हरी इति। यस्य। सुऽयुजा। विऽ
व्रता। वेः। अर्वता। अनु। शेपा। उभा। रजी इति। न। केशिना। पतिः। दन्। अपायोः। इंद्रः। पाय्जे। आ
मर्तैः। न्। शुश्रमाणः। बिभीवान्। शुभे। यत्। सुयुजे। तविषीऽवान्। सचा। आयोः। इंद्रः। चर्केषे।
आ। उपानसः। सुपर्यन्। नदयोः। विऽव्रतयोः। शूरः। इंद्रः। अधि। यः। तस्थौ। केशऽवंता। व्यचस्वंता।
न। पुष्ट्यै। वनोति। शिप्राभ्यां। शिप्रिणीऽवान्॥ रध्या॥ प्र। अस्तौत्। ऋष्वऽओजाः। ऋष्वेभिः। ततक्ष।
शूरः। शवसा। ऋभुः। न। क्रतुऽभिः। मातरिश्वा। वज्रं। यः। चक्रे। सुऽहनाय। दस्यवे। हिरीमशः। हि ७०

70

© Dharmartha Trust J&K. Digitized by eGangotri

हिरीमान्। अहुतऽहनुः। अद्भुतं। न। रजः। अव। नः। वृजिना। शिशीहि। ऋचा। वनेम। अनृचः। न।

ध अब्रह्मा। यज्ञः। ऋधक्। जोषति। त्वे इति। ऊर्ध्वा। यत्। ते। त्रेतिनी। भूत्। यज्ञस्य। धूःऽसु। सद्मन्।

सऽजूः। नावं। स्वऽयशसं। सचा। आयोः। श्रिये। ते। पृश्निः। उपऽसेचनी। भूत्। श्रिये। दर्विः। अ

रेपाः। यया। स्वे। पात्रे। सिंचसे। उत्। शतं। वा। यत्। असुर्य। प्रति। त्वा। सुऽमित्रः। इत्था। अस्तौ

त्। दुःऽमित्रः। इत्था। अस्तौत्। आवः। यत्। दस्युऽहत्ये। कुत्सऽपुत्रं। प्र। कुत्सऽवत्सं॥ २७॥ इत्यष्टमा

ष्टके पंचमोध्यायः॥ ॐ॥ उभौ भूतांशः काश्यप आश्विनमाविर्दिव्यो दक्षिणा वा प्राजापत्यों द

क्षिणां तद्वा हन्वा स्तौ चतुर्थी जगती किमिच्छंती पणिभिरसुरैर्निगूढा गा अन्वेष्टुं सरमां देव

अ.प. ग्रनीभिंद्रेण सहितांमरुद्भिः पणयो मित्रियं तः प्रोचुः सातं न्युग्मं त्याभिरनिछं तीप्रत्या चष्टे ते
७१ वदं सत्तजुहूर्ये स आयां ग्रास्तो वो र्ध्वे नाभाचे श्वदेवं घ्यनुष्टुबंतं समिद्धू एकादशाजमदग्निस्त
स्तुतो वाराम आप्रियः परे चत्वारो वैरूपां मनीषिणो दशाष्टादं ष्टू इंद्र पिबनभप्रभेदनं स्तमस्यश
71 नप्रभेदनौं स्यात्रिष्टुप् घर्मा सप्रिस्तापसो वा घर्मौ वैश्वदेवं चतुर्थी जगती चित्र इन्त्व वार्हि ह
व्यंउपरस्तुनं आग्नेयं जागतं त्रिष्टुप् शाकुर्यं तं पिबस्थो रोग्नि युतोग्नि यूपो वानवाउभिष्टुर्ध
नांनदानप्रसोशं चां चे जगत्सावग्ने हं स्युरक्षय आमहीयवं आग्नेयं राक्षोघ्नं गायत्रं विलि
वैसप्तो नैं ध्रौल्व आत्मानं नुष्टाव॥ हरिः ओम्॥ उमौ॥ ॐ इति॥ नूनं॥ नत॥ इत॥ अर्थ ये थे इति। ७१

© Dharmartha Trust J&K. Digitized by eGangotri

चितन्वाथेइति। धियः। नस्यो। अपसाऽइव। सध्रीचीना। यातवे। प्राइं। अजीगरिति। सुदिनाऽ
इव। पक्षः। आ। तं। सयेथेइति। उपराऽइव। कर्वरेषु। श्रयेथेइति। प्रायोगाऽइव। श्वाच्यो। शासुः
। आ। इथः। दूताऽइव। हि। स्थः। यशसा। जनेषु। मा। अप। स्थातं। महिषाऽइव। अवऽपानात्। साकं
ऽयुजा। शकुनस्यऽइव। पक्षा। पश्वाऽइव। चित्रा। यजुः। आ। गमिष्टं। अग्निःऽइव। देवऽयोः। दीदिऽ
वांसा। परिऽज्मानाऽइव। यजथः। पुरुऽत्रा। आपीइति। वः। अस्मेइति। पितराऽइव। पुत्रा। उग्राऽ
इव। रुचा। नृपतीइवेति नृपतीऽइव। तुर्यै। इर्यीऽइव। पुष्ट्यै। किरणाऽइव। भुज्यै। श्रुष्टीवानाऽ
इव। हवं। आ। गमिष्टं। नं। सगाऽइव। पूषर्या। शिंबाना। मित्राऽइव। क्रूता। शतरा। शातपंता। वा

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰प॰ जाऽइव। उग्रा। वयसा। घर्म्मेऽस्था। मेषाऽइव। इषा। सपर्या। पुरीषा॥ ३॥ सृण्याऽइव। जर्भरीइति।
७२ तुर्फरीतूइति। नैतोशाऽइव। तुर्फरीइति। पर्फरीका। उदन्यजाऽइव। जेमना। मदेरूइति। ता। मे। ज
रायु। अजरं। मरायु। पज्राऽइव। चर्चरं। जारं। मरायु। क्षद्मेऽइव। अर्थेषु। तर्त्तरीथः। उग्रा। ऋभूइति
। ना। आपत्। खरमज्रा। खरऽज्रुः। वायुः। न। पर्फरत्। क्षयत्। रयीणां। घर्म्माऽइव। मधु। जठरे। स
नेरूइति। भगेऽअविता। तुर्फरीइति। फारिवा। अरं। पतराऽइव। चचरा। चंद्रऽनिर्निक्। मनःऽऋं
गा। मनन्या। न। जग्मीइति। बृहंताऽइव। गंभरेषु। प्रतिऽस्थां। पादाऽइव। गाधं। तरते। विदाथः। क
र्णाऽइव। शासुः। अनु। हि। स्मराथः। अंशाऽइव। नः। भजतं। चित्रं। अप्नः। आरंगराऽइव। मधु। आ। ७२

© Dharmartha Trust J&K. Digitized by eGangotri

रा
ईर्ये थे इति । सारघाऽइव । गविनी । चीनः । बारी । कीनाऽइव । स्वेदं । आऽसिस्विदाना । क्षामऽइव । ऊ
र्जा । स्रुयवसः । अत्न्रा । सचेथे इति । रध्या । मे । स्तोमं । सतुयामे । वाजं । आ । नः । मत्रों । स्रऽरथा । इह ।
उपायातं । यशः । नाप । कं । मधु । गोषु । अंतः । आ । भूतऽअंशाः । अश्विनोः । कामं । अप्राः ॥ या । आ
विः । अभूत् । महि । माघोनं । एषां । विश्वं । जीवं । तमसः । निः । अमोचि । महि । ज्योतिः । पितृऽभिः ।
दत्तं । आ । अगात् । उरुः । पंथाः । दक्षिणायाः । अदर्शि । उच्चा । दिवि । दक्षिणाऽवंतः । अस्थुः । ये । अ
श्वऽदाः । सह । ते । सूर्येण । हिरण्यऽदाः । अमृतऽत्वं । भजंते । वासःऽदाः । सोम । प्र । तिरंते । आयुः । दे
वी । पूर्तिः । दक्षिणा । देवऽयज्या । न । कवऽअरिभ्यः । नहि । ते । पृणंति । अथ । नरः । प्रयतऽदक्षिणा

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰प॰ सः।अवयऽमिया।बहवः।पणंति।शतऽधारं।वायुं।अर्कं।स्वःऽविदं।नरऽचक्षसः।ते।अभि।चक्ष
७३ ते।हविः।ये।पणंति।प्राचायछंति।संऽगमे।ते।दक्षिणां।दुहते।सप्तऽमातरं।दक्षिणाऽवान्।प्रथमः।
73 हूतः।एति।दक्षिणाऽवान्।ग्रामऽनीः।अग्रं।एति।तं।एव।मन्ये।नऽपतिं।जनानां।यः।प्रथमः।
दक्षिणां।आऽविवाय॥३॥तं।एव।ऋषिं।तं।ऊं इति।ब्रह्माणं।आहुः।यज्ञऽन्यं।सामऽगां।उक्थऽ
शसं।सः।शुक्रस्य।तन्वः।वेद।तिस्रः।यः।प्रथमः।दक्षिणया।रराध।दक्षिणा।अश्वं।दक्षिणा
।गां।ददाति।दक्षिणा।चंद्रं।उत।यत्।हिरण्यं।दक्षिणा।अन्नं।वनुते।यः।नः।आत्मा।दक्षिणां।
वर्म।कृणुते।विऽजानन्।न।भोजाः।ममुः।न।निऽअर्थं।ईयुः।न।रिष्यंति।न।व्यथंते।ह।भोजाः। ७३

© Dharmartha Trust J&K. Digitized by eGangotri

इदं। यत्। विश्वं। भुवनं। स्वऽरिति स्वः। च। एतत्। सर्वं। दक्षिणा। एभ्यः। ददाति। भोजाः। जिग्युः। सु

रभिं। योनिं। अग्रे। भोजाः। जिग्युः। वध्वं। या। सुऽवासाः। भोजाः। जिग्युः। अंतःऽपेयं। सुरायाः। भो

जाः। जिग्युः। ये। अहूताः। प्रऽयंति। भोजाय। अश्वं। सं। मृजंति। आशुं। भोजाय। आस्ते। कन्या। शुं

भमाना। भोजस्य। इदं। पुष्करिणीऽइव। वेश्म। परिऽकृतं। देवमानाऽइव। चित्रं। भोजं। अश्वाः। सु

ष्ठुऽवाहः। वहंति। सुऽवृत्। रथः। वर्त्तते। दक्षिणायाः। भोजं। देवासः। अवत। भरेषु। भोजः। शत्रून्। सं

अनीकेषु। जेता॥ ४॥ किं। इच्छंती। सरमा। प्र। इदं। आनट्। दूरे। हि। अध्वा। जगुरिः। पराचैः। का। अ

स्मेंहितिः। का। परिऽतक्म्या। आसीत्। कथं। रसायाः। अतरः। पयांसि। इंद्रस्य। दूतीः। इषिता। च

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰प॰ रामि। महः। इच्छंती। पणयः। निऽधीन्। वः। अतिऽस्कदः। भियसा। तत्। नः। आ। ववर्त्। न। थाः। रसायाः।
७४ अतरं। पयांसि। कीदृङ्। इंद्रः। सरमे। का। दृशीका। यस्य। इदं। दूतीः। असरः। पराकात्। आ। च। गच्छात्।
74 मित्रं। एन। दधाम। अथ। गवां। गोऽपतिः। नः। भवाति। ०दम्यं। दभत्। सः। ०। असरं। पराकात्। न। तं। गू
हंति। स्रवतः। गभीराः। हताः। इंद्रेण। पणयः। शयध्वे। इमाः। गावः। सरमे। याः। ऐच्छः। परि। दिवः। अं
तान्। सुऽभगे। पतंती। कः। ते। एनाः। अव। सृजात्। अयुध्वी। उत। अस्माकं। आयुधा। संति। तिग्मा।
।५। असेन्या। वः। पणयः। वचांसि। अनिषव्याः। तन्वः। संतु। पापीः। अधृष्टः। वः। [illegible] एतवै। अस्तु।
पंथाः। बृहस्पतिः। वः। उभया। न। मृळात्। अयं। निऽधिः। सरमे। अद्रिऽबुध्नः। गोभिः। अश्वेभिः। व ७४

© Dharmartha Trust J&K. Digitized by eGangotri

सुऽभिः । निःऽऋष्टः । रक्षंति । तं । पणयः । ये । सुऽगोपाः । रेकु । पदं । अलकं । आ । जगंथ । आ । इह । गमन् । ऋ
षयः । सोमऽशिताः । अयास्यः । अंगिरसः । नवऽग्वाः । ते । एतं । ऊर्वं । [illegible] भजंत । गोनां । अथ । एतत् । व
चः । पणयः । वमन् । इत् । एव । च । त्वं । सरमे । आऽजगंथ । प्रऽबाधिता । सहसा । दैव्येन । स्वसारं । त्वा । कृ
णवै । मा । पुनः । गाः । अप । ते । गवां । सुऽभगे । भजाम । न । अहं । वेद । भ्रातृऽत्वं । नो इति । स्वसृऽत्वं । इंद्रः ।
विदुः । अंगिरसः । च । घोराः । गोऽकामाः । मे । अछदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरी
यः । दूरं । इत । पणयः । वरीयः । उत् । गावः । यंतु । मिनतीः । ऋतेन । बृहस्पतिः । याः । अविंदत् । निऽगूह्ळाः ।
सोमः । ग्रावाणः । ऋषयः । च । विप्राः ॥ ६ ॥ ते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः ।

© Dharmartha Trust J&K. Digitized by eGangotri

अ.प. मातरिश्वा। वीळुऽहराः। तपः। उग्रः। मयःऽभूः। आपः। देवीः। प्रथमऽजाः। ऋतेन। सोमः। राजा। प्रथमः।
७५ ब्रह्मऽजायां। पुनः। इति। प्र। अयच्छत्। अहृणीयमानः। अनुऽअर्तिता। वरुणः। मित्रः। आसीत्। अग्निः।
75 होता। हस्तऽगृह्य। आ। निनाय। हस्तेन। एव। ग्राह्यः। आऽधिः। अस्याः। ब्रह्मऽजाया। इयं। इति। च।
इत्। अवोचन्। न। दूताय। प्रऽहेया। तस्थे। एषा। तथा। राष्ट्रं। गुपितं। क्षत्रियस्य। देवाः। एतस्यां। अव
दन्त। पूर्वे। सप्तऽऋषयः। तपसे। ये। निऽसेदुः। भीमा। जाया। ब्राह्मणस्य। उपऽनीता। दुःऽधां। दधा
ति। परमे। विऽओमन्। ब्रह्मऽचारी। चरति। वेविषत्। विषः। सः। देवानां। भवति। एकं। अंगं। तेन। जा
यां। अनु। अविंदत्। बृहस्पतिः। सोमेन। नीतां। जुह्वं। न। देवाः। पुनः। वै। देवाः। अददुः। पुनः। मनुष्याः। ७५

© Dharmartha Trust J&K. Digitized by eGangotri

उत। राजानः। सत्यं। कृण्वानाः। ब्रह्मऽजायां। पुनः। ददुः। पुनःऽदाय। ब्रह्मऽजायां। कृत्वी। देवैः। निःऽ
किल्बिषं। ऊर्जं। पृथिव्याः। भक्त्वाय। उरुऽगायं। उप। आसते। ॥ ७ ॥ संऽइद्धः। अद्य। मनुषः। दुरोणे।
देवः। देवान्। यजसि। जातऽवेदः। आ। च। वह। मित्रऽमहः। चिकित्वान्। त्वं। दूतः। कविः। असि। प्रऽचेताः।
तनूऽनपात्। पथः। ऋतस्य। यानान्। मध्वा। संऽअंजन्। स्वदय। सुऽजिह्व। मन्मानि। धीभिः। उत। यज्ञं।
ऋंधन्। देवऽत्रा। च। कृणुहि। अध्वरं। नः। आऽजुह्वानः। ईड्यः। वंद्यः। च। आ। याहि। अग्ने। वसुऽभिः।
सऽजोषाः। त्वं। देवानां। असि। यह्व। होता। सः। एनान्। यक्षि। इषितः। यजीयान्। प्राचीनं। ब
र्हिः। प्रऽदिशा। पृथिव्याः। वस्तोः। अस्याः। वृज्यते। अग्रे। अह्नां। देवेभ्यः। अदितये। स्योनं। व्यच

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰प॰ स्वतीः। उर्वीः। याः। वि। श्रयंतां। पतिभ्यः। न। जनयः। शुंभमानाः। देवीः। द्वारः। बृहतीः। विश्वंऽइन्वाः।
७६ देवेभ्यः। भवत। सुप्रऽअयनाः। ०। आ। सुस्वयंती इति। यजते इति। उपाके इति। ०। दिव्ये इति। यो
षणे इति। बृहती इति। सुरुक्मे इति सुऽरुक्मे। अधि। श्रियं। शुक्रऽपिशँ। दधाने इति। ०। सुऽवाचा।
मिमाना। यज्ञं। मनुषः। यजध्यै। प्रऽचोदयंता। विदथेषु। कारू इति। प्राचीनं। ज्योतिः। प्रऽदिशा। दि
शंता। आ। नः। यज्ञं। भारती। तूयं। एतु। इळा। मनुषवत्। इह। चेतयंती। तिस्रः। देवीः। बर्हिः। इदं। स्यो आ
नं। सरस्वती। सुऽअपसः। सदंतु। यः। इमे इति। द्यावापृथिवी इति। जनित्री इति। रूपैः। अपिंश
त्। भुवनानि। विश्वा। तं। अद्य। होतः। इषितः। यजीयान्। देवं। त्वष्टारं। इह। यक्षि। विद्वान्। उपऽ ७६

© Dharmartha Trust J&K. Digitized by eGangotri

अवसृज।त्मन्या।सम्ऽअंजन्।देवानां।पाथः।ऋतुऽथा।हवींषि।वनस्पतिः।शमिता।देवः।अग्निः।स्वदं
तु।हव्यं।मधुना।घृतेन।सद्यः।जातः।वि।अमिमीत।यज्ञं।अग्निः।देवानां।अभवत्।पुरःऽगाः।अस्य।हो
तुः।प्रऽदिशि।ऋतस्य।वाचि।स्वाहाऽकृतं।हविः।अदंतु।देवाः।।१।।मनीषिणः।प्र।भरध्वं।मनीषां।यथा
ऽयथा।मतयः।संति।नृणां।इंद्रं।सत्यैः।आ।ईरयाम।कृतेभिः।सः।हि।वीरः।गिर्वणस्युः।विदानः।ऋत
स्य।हि।सदसः।धीतिः।अद्यौत्।सं।गार्ष्टेयः।वृषभः।गोभिः।आनट्।उत्।अतिष्ठत्।तविषेण।रवेण।
महांति।चित्।सं।विव्याच।रजांसि।इंद्रः।किल।श्रुत्यै।अस्य।वेद।सः।हि।जिष्णुः।पथिऽकृत्।सूर्या
य।आत्।मेनां।कृण्वन्।अच्युतः।भुवत्।गोः।पतिः।दिवः।सनऽजाः।अप्रतिऽइतः।॰।व्रता।अमिनात्।

© Dharmartha Trust J&K. Digitized by eGangotri

अ॰प॰ अंगिरःऽभिः । गृणानः । पुरूणि । चित् । नि । तताना । रजांसि । दाधार । यः । धरुणं । सत्यऽता । इंद्रः । दिवः ।
७७ प्रतिऽमानं । पृथिव्याः । विश्वा । वेद । सवना । हंति । शुष्णं । महि । चित् । द्यां । आ । अतनोत् । सूर्येण । चा
77 स्कंभ । चित् । स्कंभनेन । स्कभीयान् ॥ ३ ॥ वज्रेण । हि । वृत्रऽहा । वृत्रं । अस्तः । अदेवस्य । शूशुवान
स्य । मायाः । वि । धृष्णो इति । अत्र । धृषता । जघंथ । अथ । अभवः । मघऽवन् । बाहुऽओजाः । सचंत ।
यत् । उषसः । सूर्येण । चित्रां । अस्य । केतवः । रां । अविंदन् । आ । यत् । नक्षत्रं । ददृशे । दिवः । न । पुनः ।
यतः । नकिः । अद्धा । नु । वेद । दूरं । किल । प्रथमाः । जग्मुः । आसां । इंद्रस्य । याः । प्रऽसवे । सस्रुः । आपः । कं
स्वित् । अग्रं । क्व । बुध्नः । आसां । आपः । मध्यं । क्व । वः । नूनं । अंतः । सृजः । सिंधून् । अहिना । जग्रसान् । ७७

© Dharmartha Trust J&K. Digitized by eGangotri

आत्। इत्। एताः। प्र। विविज्रे। जवेन। मुमुक्षमाणाः। उत। याः। मुमुचे। अध। इत्। एताः। न। रमन्ते। निःऽति
क्ताः। सध्रीचीः। सिंधुं। उशतीःऽइव। आयन्। सनात्। जारः। आऽरितः। पूःऽभित्। आसां। अस्तं। आ।
ते। पार्थिवा। वसूनि। अस्मे इति। जग्मुः। सूनृताः। इंद्र। पूर्वीः॥ ३३॥ इंद्र। पिब। प्रतिऽकामं। सुतस्य। प्रा
तःऽसावः। तव। हि। पूर्वऽपीतिः। हर्षस्व। हंतवे। शूर। शत्रून्। उक्थेभिः। ते। वीर्या। प्र। ब्रवाम॥ यः। ते। रथः
। मनसः। जवीयान्। आ। इंद्र। तेन। सोमऽपेयाय। याहि। तूयं। आ। ते। हरयः। प्र। द्रवंतु। येभिः। यासि
। वृषऽभिः। मंदमानः। हरित्वता। वर्चसा। सूर्यस्य। श्रेष्ठैः। रूपैः। तन्वं। स्पर्शयस्व। अस्माभिः। इंद्र। स
खिऽभिः। हुवानः। सध्रीचीनः। मादयस्व। निऽसद्य॥ यस्य। त्यत्। ते। महिमानं। मदेषु। इमे इति। मही इ

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· तिः। रोदसी इति। न। अविविक्तां। तत्र। ओकः। आ। हरिऽभिः। इंद्र। युक्तैः। प्रियेभिः। याहि। प्रियं। अन्नं। अच्छ।
७८ यस्य। शश्वत्। पपिऽवान्। इंद्र। शत्रून्। अननुऽकृत्या। रण्या। चकर्थ। सः। ते। पुरंऽधिं। तविषीं। इयर्त्ति। सः। ते।
78 मदाय। सुतः। इंद्र। सोमः॥ ३॥ इदं। ते। पात्रं। सनऽवित्तं। इंद्र। पिब। सोमं। एना। शतक्रतो इति शतऽक्रतो। पू-
र्णः। आऽहावः। मदिरस्य। मध्वः। यं। विश्वे। इत्। अभिऽहर्यंति। देवाः। वि। हि। त्वां। इंद्र। पुरुधा। जनासः। हि-
तऽप्रयसः। वृषभ। ह्वयंते। अस्माकं। ते। मधुमत्ऽतमानि। इमा। भुवन्। सवना। तेषु। हर्य। प्र। ते। इंद्र। पू-
र्व्याणि। प्र। नूनं। वीर्या। वोचं। प्रथमा। कृतानि। सतीनऽमन्युः। अश्रथयः। अद्रिं। सुऽवेदनां। अकृणोः।
ब्रह्मणे। गां। नि। सु। सीद। गणऽपते। गणेषु। त्वां। आहुः। विप्रऽतमं। कवीनां। न। ऋते। त्वत्। क्रियते। किं। ७८

© Dharmartha Trust J&K. Digitized by eGangotri

ना

चनः। आरे। मंहां। अर्कं। मघऽवन्। चित्रं। अर्च। अभिऽस्व्या। नः। मघऽवन्। नाधमानान्। सखे। बोधि। वसुऽपते।
सखीनां। रणं। रुधि। रणऽकृत्। सस्यऽशुष्मं। अभक्तः। चित्। आ। भज। राये। अस्मान्। ॥ ३॥ तं। अस्य।
द्यावा। पृथिवी इति। सऽचेतसा। विश्वेभिः। देवैः। अनु। इत्था। आवर्ततां। यत्। ऐत्। कृण्वानः। महिमानं। इं-
द्रियं। पीवी। सोमस्य। क्रतुऽमान्। अवऽईत्। तं। अस्य। विष्णुः। महिमानं। ओजसा। अंशुं। दधन्वान्।
मधुनः। वि। रप्शते। देवेभिः। इंद्रः। मघऽवा। सयावऽभिः। वृत्रं। जघन्वान्। अभवत्। वरेण्यः। वृत्रेण। यत्।
अहिना। बिभ्रत्। आयुधा। संऽअस्थिथाः। युधये। शंसं। आऽविदे। विश्वे। ते। अत्र। मरुतः। सह। त्मना।
अवर्धन्। उग्र। महिमानं। इंद्रियं। जज्ञानः। एव। वि। अबाधत। स्पृधः। प्र। अपश्यत्। वीरः। अभि। पौंस्यं।

© Dharmartha Trust J&K. Digitized by eGangotri

अ.प. रणं। अस्कभ्नात्। अद्रिं। अर्वा। सऽस्यदः। सृजत्। अस्तभ्नात्। नाकं। सुऽअपस्यया। पृथुं। आ। नु। इंद्रः। सत्रा। त
७० नविषीः। अपस्यत। वरीयः। द्यावापृथिवी इति। अबाधत। अवा। अभरत्। धृषितः। वज्रं। आयसं। शेवं।
79 मित्राय। वरुणाय। दाशुषे ॥ ३४ ॥ इंद्रस्य। अत्र। तविषीभ्यः। विऽरप्शिनः। ऋघायतः। अरंहयंत। मन्यवे।
वृत्रं। यत्। उग्रः। वि। अस्तभ्नात्। ओजसा। अपः। बिभ्रतं। तमसा। परिऽवृतं। या। वीर्याणि। प्रथमानि। क
र्त्वानि। महिऽत्वेभिः। यतमानौ। संऽईयतुः। ध्वांतं। तमः। अव। दध्वसे। हते। इंद्रः। मह्ना। पूर्वऽहूतौ। अपस्य
त। विश्वे। देवासः। अध। वृष्णे। मिते। अवर्द्धयन्। सोमऽवत्या। वचस्यया। रुद्रं। वृत्रं। अहिं। इंद्रस्य। ह
न्मना। अग्निः। न। जंभैः। तृषु। अन्नं। आवयत्। भूरि। दक्षेभिः। वचनेभिः। ऋक्वऽभिः। सख्येभिः। सख्या ८९

© Dharmartha Trust J&K. Digitized by eGangotri

नि। प्र। वोचत। इंद्रः। धुनिं। च। चुमुरिं। च। दंभयन्। श्रद्धाऽमनस्या। शृणुते। दभीतये। त्वं। पुरूणि। आ। भर।
सुऽअश्व्या। येभिः। मंसै। निःऽवचनानि। शंसन्। सुऽगेभिः। विश्वा। दुःऽइता। तरेम। विदोइति। सुऽनः।
उर्विया। गाधं। अद्य। १५। घर्म्मा। संऽअंता। त्रिऽवर्तं। वि। आपतुः। नयोः। जुष्टिं। मातरिश्वा। जगाम।
दिवः। पयः। दिधिषाणाः। अवेषन्। विदुः। देवाः। सहऽसामानं। अर्कं। तिस्रः। देष्ट्राय। निःऽऋतीः। उप। आ।
सते। दीर्घऽश्रुतः। वि। हि। जानंति। वन्हयः। तासां। नि। चिक्युः। कवयः। निऽदानं। परेषु। याः। गुह्येषु। व्र
तेषु। चतुःऽकपर्दा। युवतिः। सुऽपेशाः। घृतऽप्रतीका। वयुनानि। वस्ते। तस्यां। सुऽपर्णा। वृषणा। नि।
सेदतुः। यत्र। देवाः। दधिरे। भागऽधेयं। एकः। सुऽपर्णः। सः। समुद्रं। आ। विवेश। सः। इदं। विश्वं। भुवं

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· नं।वि।चष्टे।तं।पाकेन।मनसा।अपश्यं।अंतितः।तं।माता।रेळ्हि।सः।ऊं इति।रेळ्हि।मातरं।सुऽपर्णं।वि
८० प्राः।कवयः।वचःऽभिः।एकं।संतं।बहुधा।कल्पयंति।छंदांसि।च।दधतः।अध्वरेषु।ग्रहान्।सोमस्य।
80 मिमते।द्वादश॥३॥षट्ऽत्रिंशान्।च।चतुरः।कल्पयंतः।छंदांसि।च।दधतः।आऽद्वादशं।यज्ञं।विऽमा
य।कवयः।मनीषा।ऋक्ऽसामाभ्यां।प्र।रथं।वर्तयंति।चतुःऽदश।अन्ये।महिमानः।अस्य।तं।धीराः।
वाचा।प्र।नयंति।सप्त।आप्तानं।तीर्थं।कः।इह।प्र।वोचत्।येन।पथा।प्रऽपिबंते।सुतस्य।सहस्रधा।
पंचऽदशानि।उक्था।यावत्।द्यावापृथिवी इति।तावत्।इत्।तत्।सहस्रधा।महिमानः।सहस्रं।याव
त्।ब्रह्म।विऽस्थितं।तावती।वाक्।कः।छंदसां।योगं।आ।वेद।धीरः।कः।धिष्ण्यां।प्रति।वाचं।पपाद। ८०

© Dharmartha Trust J&K. Digitized by eGangotri

कं।ऋत्विजां।अह्नं।शूरं।आहुः।हरीइति।इंद्रस्य।नि।चिकाय।कः।स्वित्।भूम्याः।अंतं।परि।एके।
चरंति।रथस्य।धूःऽसु।युक्ताः।सः।अस्थुः।श्रमस्य।दायं।वि।भजंति।एभ्यः।यदा।यमः।भवति।ह
र्म्ये।हितः॥१७॥चित्रः।इत्।शिशोः।तरुणस्य।वक्षथः।न।यः।मातरौ।अपि।एति।धातवे।अनूधाः।
यदि।जीजनत्।अध।च।नु।ववक्ष।सद्यः।महि।दूत्यं।चरन्।अग्निः।ह।नाम।धायि।दन्न्।अपःऽत
मः।सं।यः।वना।युवते।भस्मना।दता।अभिऽप्रमुरा।जुह्वा।सुऽअध्वरः।इनः।न।प्रोथमानः।यव
से।वृषा।तं।वः।विं।न।द्रुऽसदं।देवं।अंधसः।इंदुं।प्रोथंतं।प्रऽवपंतं।अर्णवं।आसा।वह्निं।न।शोचि
षा।विऽरप्शिनं।महिऽव्रतं।न।सरजंतं।अध्वनः।वि।यस्य।ते।ज्रयसानस्य।अजर।धक्षोः।न।वा

© Dharmartha Trust J&K. Digitized by eGangotri

अ.प. तां।परि।संति।अच्युताः।आ।रण्वासः।युयुधयः।न।सत्वनं।त्रितं।नशंत।प्र।शिषंतः।इष्टये।स्वः।इत।
८३ अग्निः।कण्वऽतमः।कण्वऽसखा।०।अग्निः।पातु।गृणतः।अग्निः।सूरीन्।अग्निः।ददातु।तेषां।अ
वः।नः।।३८।।वाजिन्ऽतमाय।सह्यसे।सुऽपित्र्य।तृषु।च्यवानः।अनुऽजातऽवेदसे।अनुद्रे।चित्।
यः।धृषता।वरं।सते।महिन्ऽतमाय।धन्वना।इत्।अविष्यते।एव।अग्निः।मर्तैः।सह।सूरिऽभिः।
वसुः।स्तवे।सहसः।सूनरः।नृऽभिः।मित्रासः।न।ये।सुऽधिताः।ऋतऽयवः।द्यावः।न।द्युम्नैः।अ
भि।संति।मानुषान्।ऊर्जः।नपात्।सहसावन्।इति।त्वा।उपऽस्तुतस्य।वंदते।वृषा।वाक्।ग्ने। तां स्तो
इति।त्वा।अग्ने।वह्निऽहव्यस्य।पुत्राः।उपऽस्तुतासः।ऋषयः।अवोचन्।तान्।च।पाहि।गृणतः। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

चासूरीन्।वषट्।वषट्।इति।ऊर्ध्वासः।अनक्षन्।नमः।नमः।७।१०।।पिब।सोमं।महते।इंद्रियाय।
पिब।वृत्राय।हंतवे।श।विष्ण।पिब।राये।श।वसो।हूयमानः।पिब।मध्वः।तृपत्।इंद्र।आ।वृषस्व।
अस्य।पिब।क्षुऽमतः।प्रऽस्थितस्य।इंद्र।सोमस्य।वरं।आ।सुतस्य।स्वस्तिऽदाः।मनसा।मादयस्व।
अर्वाचीनः।रेवते।सौभगाय।ममत्तु।वा।दिव्यः।सोमः।इंद्र।ममत्तु।यः।सूयते।पार्थिवेषु।ममत्तु।
येन।वरिवः।चकर्थ।ममत्तु।येन।निऽरिणासि।शत्रून्।आ।द्विऽबर्हाः।अमिनः।यातु।इंद्रः।वृ
षा।हरिऽभ्यां।परिऽसिक्तं।अंधः।गवि।आ।सुतस्य।प्रऽभृतस्य।मध्वः।सत्रा।खेदां।अरुशऽहा।
आ।वृषस्व।नि।तिग्मानि।भ्राशयन्।भ्राश्यानि।ओं।उग्राय।ते।सहः।बलं।ददामि।प्रतिऽइत्य।श मव:

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· नृऽनृ। विऽगदेषु। रश्च॥ २०॥ वि। अर्य्यः। इंद्र। तनुहि। श्रवांसि। ओजः। स्थिराऽइव। धन्वनः। अभिऽमातीः। अ
८२ स्मद्र्यक्। वव्रधानः। सहःऽभिः। अनि॥ मृष्टः। तन्वं। ववृधस्व। इदं। हविः। मघऽवन्। तुभ्यं। राता। प्रति। स
म्ऽराट्। अहृणानः। गृभाय। तुभ्यं। सुतः। मघऽवन्। तुभ्यं। पक्वः। अद्धि। इंद्र। पिब। च। प्रऽस्थितस्य। अद्रि
ऽइत्। इंद्र। प्रऽस्थिता। इमा। हवींषि। चनः। दधिष्व। पचता। उत। सोमं। प्रयस्वंतः। प्रति। हर्य्यामसि। त्वा।
सत्याः। संतु। यजमानस्य। कामाः। प्र। इंद्राग्निऽभ्यां। सुऽवचस्यां। इयर्म्मि। सिंधौऽइव। प्र। ईरयं। नावं
। अर्कैः। अयाःऽइव। परि। चरंति। देवाः। ये। अस्मभ्यं। धनऽदाः। उत्ऽभिदः। च॥ २१॥ न। वै। ऊं इति। देवाः। क्षु
धं। इत्। वधं। ददुः। उत। आशितं। उप। गच्छंति। मृत्यवः। उतो इति। रयिः। पृणतः। न। उप। दस्यति। उत। अ ८२

© Dharmartha Trust J&K. Digitized by eGangotri

पृणं न्। मर्डितारं। न। विंदते। यः। आध्राय। चकमानाय। पित्वः। अन्नऽवान्। सन्। रफिताय। उपऽजग्मुषे। स्थि
रं। मनः। कृणुते। सेवते। पुरा। उतोइति। चित्। सः। मर्डितारं। न। विंदते। सः। इत्। भोजः। यः। गृहवे। ददाति। अ
न्नंऽकामाय। चरते। कृशाय। अरं। अस्मै। भवति। यामंऽहूतौ। उत। अपरीषु। कृणुते। सखायं। न। सः। स
खा। यः। न। ददाति। सख्ये। सचाऽभुवे। सचमानाय। पित्वः। अप। अस्मात्। प्र। इयात्। न। तत्। ओकः। अ
स्ति। पृणंतं। अन्यं। अरणं। चित्। इच्छेत्। पृणीयात्। इत्। नाधमानाय। तव्यान्। द्राघीयांसं। अनु। पश्येत्।
पंथां। ओइति। हि। वर्तंते। रथ्याऽइव। चक्रा। अन्यंऽअन्यं। उप। तिष्ठंत। रायः। ॥२२॥ मोघं। अन्नं। विंदते। अ
प्रऽचेताः। सत्यं। ब्रवीमि। वधः। इत्। सः। तस्य। न। अर्यमणं। पुष्यति। नोइति। सखायं। केवलऽअघः। भव

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· ति। केवलऽआदी। कृषन्। इत्। फालः। आशितं। कृणोति। यन्। अध्वानं। अप। वृङ्क्ते। चरित्रैः। वदन्। ब्रह्मा। अ
८३ वदतः। वनीयान्। पृणन्। आपिः। अपृणन्तं। अभि। स्यात्। एकऽपात्। भूयः। द्विऽपदः। वि। चक्रमे। द्विऽपात्।
त्रिऽपादं। अभि। एति। पश्चात्। चतुःऽपात्। एति। द्विऽपदां। अभिऽस्वरे। संऽपश्यन्। पङ्क्तीः। उपऽतिष्ठमानः।
समौ। चित्। हस्तौ। न। समं। विविष्टः। संऽमातरा। चित्। न। समं। दुहाते इति। यमयोः। चित्। न। समा। वीर्या
णि। ज्ञाती इति। चित्। सन्तौ। न। समं। पृणीतः। ८४॥ अग्ने। हंसि। नि। अत्रिणं। दीद्यत्। मर्त्येषु। आ। स्वे।
क्षये। शुचिऽव्रत। उत्। तिष्ठसि। सुऽआहुतः। घृतानि। प्रति। मोदसे। यत्। त्वा। स्रुचः। संऽअस्थिरन्। सः।
आऽहुतः। वि। रोचते। अग्निः। ईळेन्यः। गिरा। स्रुचा। प्रतीकं। अज्यते। घृतेन। अग्निः। सं। अज्यते। मधुऽ ८३

83

© Dharmartha Trust J&K. Digitized by eGangotri

प्रतीकः। आऽहुतः। रोचमानः। विभाऽवसुः। जरमाणः। सं। इध्यसे। देवेभ्यः। हव्यऽवाहन। तं। त्वा। हवंत।
मर्त्यीः॥ २४॥ तं। मर्त्ताः। अमर्त्यं। घृतेन। अग्निं। सपर्यत। अदाभ्यं। गृहऽपतिं। अदाभ्येन। शोचिषा। अ
ग्ने। रक्षः। त्वं। दह। गोपाः। ऋतस्य। दीदिहि। सः। त्वं। अग्ने। प्रतीकेन। प्रति। ओष। यातुऽधान्यः। उरुऽक्ष
येषु। दीद्यत्। तं। त्वा। गीःऽभिः। उरुऽक्षयाः। हव्यऽवाहं। सं। ईधिरे। यजिष्ठं। मानुषा। जनाः॥ २५॥ इति। वै।
इति। मे। मनः। गां। अश्वं। सनुयां। इति। कुवित्। सोमस्य। अपां। इति। प्र। वाताः। ऽइव। दोधतः। उत्।
मा। पीताः। अयंसत। ० रथं। अश्वाःऽइव। आशवः। ० उप। मा। मतिः। अस्थित। वाश्रा। पुत्रंऽइव। प्रियं। ०
अहं। तष्टाऽइव। वंधुरं। परि। अचामि। हृदा। मतिं। ० नहि। मे। अक्षिऽपत्। चन। अछांत्सुः। पंच। कृष्ट

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· यः।०।२६।। नहि। मे। रोदसी इति। उभे इति। अन्यं। पक्षं। चन। प्रति। ०अभि। द्यां। महिना। भुवं। अभि। इमां
८४ । पृथिवीं। महीं। ०हं नो। अहं। पृथिवीं। इमां।। नि। दधानि। इह। वा। इह। वा। ०। ओषं। इत्। पृथिवीं। अहं।
जंघनानि। दिवि। मे। अन्यः। पक्षः। अधः। अन्यं। अची कृषं। ०अहं। अस्मि। महा। महः। अभि। न
85 भ्यं। कुतः। ईबतः। गृहः। यामि। अरंकृतः। देवेभ्यः। हव्यऽवाहनः।०।२७। इति अष्टमाष्टके षष्ठोध्या
यः।। ।।ॐ।। तदिन्नवाथर्वणो बृहद्दिवो थर्वहिरण्यगर्भोदक्षोहिरण्यगर्भः प्राजापत्यः कायंवसुनाद्दे
चित्रमहावासिष्ठं आग्नेयंजागतमाद्यां पंचमीचतैयंवेनोवैन्यमिमन्नोनवैश्चुत्तमोनिहवो
ग्निवरुणसोमानामाद्याग्नेयीतिस्त्रश्चाग्नेरात्मस्तवः शिष्टा यथानिपातं सप्तमीजगत्यहम ८४

© Dharmartha Trust J&K. Digitized by eGangotri

ष्टोवागांभण्यामानंतुष्टावद्वितीयाजगतीनतंशैलूषःकुल्मलबर्हिषोवामदेव्योवांहोमुग्वैश्वदेव
मुपरिष्टाद्बार्हतमंस्यात्रिष्टुब्भात्रीकुशिकःसौभरोरात्रिर्वाभारद्वाजीरात्रिवंगायत्रंममाग्नेनववि स्त
हव्योवैश्वदेवंजगत्यंतंनासत्स्यत्तःप्रजापतिःपरमेष्ठीभाववृत्तंतुयोयज्ञोयज्ञःप्राजापत्योजग
त्यापापप्राचःसुकीर्तिःकाक्षीवतोघो[illegible]नामध्येनुष्टुप्सोत्तराचाश्विन्योबीजानंशकपूतोना
मैधोमैत्रावरुणंन्यंकुसारिण्याद्यालिंगोक्तदेवतास्यामहासनोबृहस्पत्योपांत्येप्रस्तार
पंक्तीरोषाविराड्रूपाःप्रोषुसुदाःपैजवनःशाक्करमहापाङ्क्तौवाद्योत्तचौत्रिष्टुबंतमुभयन्मा
धालायोवनाश्चोमहापांक्तंपंक्तिरंस्यानामध्यर्द्धगोधापश्यद्यस्मिन्कुमारोयामायनो

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ अ॰ याममानुष्टुभंहि केशीमुनयोवातरशनाजूतिर्वातजूतिर्विप्रजूतिरषाणकःकरिक्रतएतशाश्र
८५ ष्यश्रृंगश्चैकर्चाःकेशिनमुनदेवाःसप्तऋषयएकर्चावैश्वदेवंतवत्येपङ्क्गऔरवोजागतंस्सूर्य
85 रश्मिर्देवगंधर्वौविश्वावसुरात्मानमस्तौत्पूर्वार्द्धंसविनारमग्नेतवाग्निःपावकआग्नेविष्टार यं
पंक्तीतिस्त्रःसतोबृहत्यउपरिष्टाज्ज्योतिरग्नेअछाग्निस्तापसोवैश्वदेवमानुष्टुभंह्यायमश्रेष्ठ
चाःशार्ङ्गजरिताद्रोणःसारिसृक्कःस्तंबमित्रश्चाग्नेयमाद्येजगत्यौचतस्रास्त्रिष्टुभः॥
ॐ॥ततादिता॥आसा॥भुवनेषु॥ज्येष्ठं॥यतः॥जज्ञे॥उग्रः॥त्वेषऽनृम्णः॥सद्यः॥जज्ञानः॥नि॥रिणाति॥श
त्रून्॥अनु॥यां॥मदंति॥ऊमाः॥वृवधानः॥शवसा॥भूरिऽओजाः॥शत्रुः॥दासाय॥भियसं॥दधाति॥ ८५
विश्वे॥

© Dharmartha Trust J&K. Digitized by eGangotri

अग्निःऽअनत्रा। च। विःऽअनत्रा। च। सस्निं। सं। ते। नवंत। प्रऽभृता। मदेषु। त्वे इति। क्रतुं। अपि। वृंजंति। विश्वे।
एते। द्विः। यत्। त्रिः। भवंति। ऊमाः। स्वादोः। स्वादीयः। स्वादुना। सृज। सं। अदः। सु। मधु। मधुना। अभि। योधीः।
इति। चित्रा। हि। त्वा। धना। जयंतं। मदेऽमदे। अनु। मदंति। विप्राः। ओजीयः। धृष्णो इति। स्थिरं। आ। तनुष्व। ष्णो २
मा। त्वा। दभन्। यातुऽधानाः। दुःऽएवाः। त्वया। वयं। शाशद्महे। रणेषु। प्रऽपश्यंतः। युधेन्यानि। भूरि।
चोदयामि। ते। आयुधा। वचःऽभिः। सं। ते। शिशामि। ब्रह्मणा। वयांसि॥ ३॥ स्तुषेय्यं। पुरुऽवर्पसं।
ऋभ्वं। इनःऽतमं। आप्त्यं। आप्त्यानां। आ। दर्षते। शवसा। सप्त। दानून्। प्र। साक्षते। प्रतिऽमाना
नि। भूरि। नि। तत्रा। दधिषे। अवरं। परं। च। यस्मिन्। आविथ। अवसा। दुरोणे। आ। मातरा। स्थाप

© Dharmartha Trust J&K. Digitized by eGangotri

अ·प· यसे।जिगत्नू इति।अतः।इनो।षि।कवैरा।पुरूणि।इमा।ब्रह्म।बृहत्ऽदिवः।विवक्ति।इंद्राय।शूषं।अग्रियः।
८६ स्वःऽसाः।महः।गोत्रस्य।क्षयति।स्वऽराजः।०।एव।महान्।बृहत्ऽदिवः।अथर्वा।अवोचत्।स्वां।तन्वं।इंद्रं।
एव।स्वसारः।मातरिभ्वरीः।अरिप्राः।हिन्वंति।च।शवसा।वर्द्धयंति।च।।२।।हिरण्यऽगर्भः।सं।अवर्त्तत।
86 अग्रे।भूतस्य।जातः।पतिः।एकः।आसीत्।सः।दाधार।पृथिवीं।द्यां।उत।इमां।कस्मै।देवाय।हविषा।
विधेम।यः।आत्मऽदाः।बलऽदाः।यस्य।विश्वे।उपऽआसते।प्रऽशिषं।यस्य।देवाः।यस्य।छाया।अमृ
तं।यस्य।मृत्युः।०।यः।प्राणतः।निऽमिषतः।महिऽत्वा।एकः।इत्।राजा।जगतः।बभूव।यः।ईशे।अस्य।
द्विऽपदः।चतुःऽपदः।०।यस्य।इमे।हिमऽवंतः।महिऽत्वा।यस्य।समुद्रं।रसया।सह।आहुः।यस्य।इमाः। ८६

© Dharmartha Trust J&K. Digitized by eGangotri

४ अग्निं। ततः। देवानां। सं। अवर्तत। असुः। एकः। ० यः। चित्। आपः। महिना। परिऽअपश्यत्। दक्षं। दधानाः। जनयंतीः। ४
प्रऽदिशः। यस्य। बाहू इति। ० येन। द्यौः। उग्रा। पृथिवी। च। दृळ्हा। येन। स्वरिति स्वः। स्तभितं। येन। नाकः।
यः। अंतरिक्षे। रजसः। विऽमानः। ०।३। यं। क्रंदसी इति। अवसा। तस्तभाने इति। अभि। ऐक्षेतां। मनसा।
रेजमाने इति। यत्र। अधि। सूरः। उत्ऽइतः। विऽभाति। ० आपः। ह। यत्। बृहतीः। विश्वं। आयन्। गर्भं। दधा
नाः। जनयंतीः। यज्ञं। यः। देवेषु। अधि। देवः। एकः। आसीत्। ० मा। नः। हिंसीत्। जनिता। यः। पृथिव्याः। यः।
वा। दिवं। सत्यऽधर्मा। जजान। यः। च। अपः। चंद्राः। बृहतीः। जजान। ० प्रजापते। न। त्वत्। एतानि। अन्यः। विश्वा।
जातानि। परि। ता। बभूव। यत्ऽकामाः। ते। जुहुमः। तत्। नः। अस्तु। वयं। स्याम। पतयः। रयीणां।। ४।। वसुना। चित्रऽ
महसं। गृणीषे। वामं। शेवं। अद्विषेण्यं। सः। रासते। शुरुधः। विश्वऽधायसः। अग्निः। होता। गृहऽपतिः।
अतिथिं।

© Dharmartha Trust J&K. Digitized by eGangotri

अ.१. सुऽवीर्य्यं।जुषाणः।अग्ने।प्रति।हर्य।मे।वचः।विश्वानि।विद्वान्।वयुनानि।सुक्रतो इति सुऽक्रतो।घृतऽनिर्णि
२८ क्।ब्रह्मणे।गातुं।आ।ईरय।त्वं।देवाः।अजनयन्।अनु।व्रतं।सप्त।धामानि।परिऽयन्।अमर्त्यः।दाशत्।दाशु
षे।सुऽकृतं।मम।महस्वान्।सुऽवीरेण।रयिणा।अग्ने।सुऽआभुवा।यः।ते।आनट्।संऽइधा।तं।जुषस्व।०।हविष्मंतः।
87 ईळते।सप्त।वाजिनं।शृण्वंतं।अग्निं।घृतऽपृष्ठं।उक्षणं।पृणंतं।देवं।पृणते।सुऽवीर्य्यं।त्वं।दूतः।प्रथमः।वरेण्यः।।
सः।हूयमानः।अमृताय।मत्स्व।त्वां।मर्जयन्।मरुतः।दाशुषः।गृहे।त्वां।स्तोमेभिः।भृगवः।वि।रुरुचुः।।५।।
इषं।[illegible]।दुहन्।सुऽदुघां।विश्वऽधायसं।यज्ञऽप्रिये।यजमानाय।सुक्रतो इति सुऽक्रतो।अग्ने।घृतऽस्नुः।त्रिः।
ऋतानि।दीद्यत्।वर्तिः।यज्ञं।परिऽयन्।सुक्रतुऽयसे।त्वां।इत्।अस्याः।उषसः।विऽउष्टिषु।दूतं।कृण्वानाः। ८८

© Dharmartha Trust J&K. Digitized by eGangotri

य।

अयजंत। मानुषाः। त्वां। देवाः। महयाय्यै। ववृधुः। आज्यं। अग्ने। निऽमृजंतः। अध्वरे। नि। त्वा। वसिष्ठाः। अह्वंत।
वाजिनं। गृणंतः। अग्ने। विदथेषु। वेधसः।०। धारय।०।६।। अयं। वेनः। चोदयत्। पृश्निऽगर्भाः। ज्योतिःऽजरायुः।
रजसः। विऽमाने। इमं। अपां। संऽगमे। सूर्यस्य। शिशुं। न। विप्राः। मतिऽभिः। रिहंति। समुद्रात्। ऊर्मिं। उत्। इ
यर्ति। वेनः। नभःऽजाः। पृष्ठं। हर्यतस्य। दर्शि। ऋतस्य। सानौ। अधि। विष्टपि। भ्राट्। समानं। योनिं। अभि।
त। अनूष व्राः। समानं। पूर्वीः। अभि। वावशानाः। तिष्ठन्। वत्सस्य। मातरः। सऽनीळाः।०। चक्रमाणाः। रिहंति
मध्वः। अमृतस्य। वाणीः। जानंतः। रूपं। अकृपंत। विप्राः। मृगस्य। घोषं। महिषस्य। हि। ग्मन्। ऋतेन। यं
तः। अधि। सिंधुं। अस्थुः। विदत्। गंधर्वः। अमृतानि। नाम। अप्सराः। जारं। उपऽसिष्मियाणा। योषा।। बि

© Dharmartha Trust J&K. Digitized by eGangotri

प-अ- भर्ति। परमे। विऽओमन्। चरत्। प्रियस्य। योनिषु। प्रियः। सन्। आसीदत्। पक्षी। हिरण्ययः। सः। वेनः॥७॥ नाके। सुऽ
८८ पर्णं। उप। यत्। पतन्तं। हृदा। वेनन्तः। अभि। अचक्षत। त्वा। हिरण्यऽपक्षं। वरुणस्य। दूतं। यमस्य। योनौ। शकु
३ र्ध्वो नं। भुरण्युं।०। प्रत्यङ्। चित्रा। बिभ्रत्। अस्य। आयुधानि।०। नाम। जनत। प्रियाणि। द्रप्सः। समुद्रं। अभि। य
त्। जिगाति। पश्यन्। गृध्रस्य। चक्षसा। विऽधर्मन्।०। चकानः। तृतीये। चक्रे। रजसि। प्रियाणि॥८॥ इमं।
नः। अग्ने। उप। यज्ञं। आ। इहि। पंचऽयामं। त्रिऽवृतं। सप्तऽतंतुं। असः। हव्यऽवाट्। उत। नः। पुरःऽगाः। ज्यो
क्। एव। दीर्घं। तमः। आ। अशयिष्ठाः। अदेवात्। देवः। प्रऽचता। गुहा। यन्। प्रऽपश्यमानः। अमृतऽत्वं।
एमि। शिवं। यत्। सन्तं। अशिवः। जहामि। स्वात्। सख्यात्। अरणीं। नाभिं। एमि॥ पश्यन्। अन्यस्याः। ८८

© Dharmartha Trust J&K. Digitized by eGangotri

अथिंथि। वयायाः। ऋतस्य। धाम। वि। मिमे। पुरूणि। शंसामि। पित्रे। असुराय। शेवं। अयज्ञियात्। यज्ञियं।
भागं। एमि। बह्वीः। समाः। अकरं। अंतः। अस्मिन्। इंद्रं। वृणानः। पितरं। जहामि। अग्निः। सोमः। वरुणः। ते।
च्यवंते। परिऽआवर्त्तन्। राष्ट्रं। तत्। अवामि। आऽयन्। निःऽमायाः। ऊं इति। त्ये। असुराः। अभूवन्। त्वं। च। मा।
वरुण। कामयासै। ऋतेन। राजन्। अनृतं। विऽविंचन्। मम। राष्ट्रस्य। अधिऽपत्यं। आ। इहि। २। इदं। स्वः।
इदं। इत्। आस। वामं। अयं। प्रऽकाशः। उरु। अंतरिक्षं। हनाव। वृत्रं। निःऽएहि। सोम। हविः। त्वा। सतं। हविषा।
यजाम। कविः। कविऽत्वा। दिवि। रूपं। आ। असजत्। अप्रऽभूती। वरुणः। निः। अपः। सृजत्। क्षेमं। कृण्वा।
नाः। जनयः। न। सिंधवः। ताः। अस्य। वर्णं। शुचयः। भरिभ्रति। ताः। अस्य। ज्येष्ठं। इंद्रियं। सचंते। ताः।

© Dharmartha Trust J&K. Digitized by eGangotri

प०अ० ई। आ। क्षेति। स्वधया। मदंती। ता। ई। विशः। न। राजानं। वृणाना। बीभत्सुवः। अप। वृत्रात्। अतिष्ठन्।
८१ बीभत्सूनां। सऽयुजं। हंसं। आहुः। अपां। दिव्यानां। सख्ये। चरंतं। अनुऽस्तुभं। अनु। चर्चूर्यमाणं। इंद्रं।
नि। चिक्युः। कवयः। मनीषा॥ १०॥ अहं। रुद्रेभिः। वसुऽभिः। चरामि। अहं। आदित्यैः। उत। विश्वऽदेवैः। अ
89 हं। मित्रावरुणा। उभा। बिभर्मि। अहं। इंद्राग्नी इति। अहं। अश्विना। उभा। अहं। सोमं। आहनसं। बि
भर्मि। अहं। त्वष्टारं। उत। पूषणं। भगं। अहं। दधामि। द्रविणं। हविष्मते। सुप्रऽअव्ये। यजमानाय। सु
न्वते। अहं। राष्ट्री। संऽगमनी। वसूनां। चिकितुषी। प्रथमा। यज्ञियानां। तां। मा। देवाः। वि। अदधुः।
पुरुऽत्रा। भूरिऽस्थात्रां। भूरि। आऽवेशयंतीं। मया। सः। अन्नं। अत्ति। यः। विऽपश्यति। यः। प्राणिति। ८१

© Dharmartha Trust J&K. Digitized by eGangotri

यः। ईं। शृणोति। उक्तं। अमंतवः। मां। ते। उप। क्षियंति। श्रुधि। श्रुत। श्रद्धिऽवं। ते। वदामि। अहं। एव। स्वयं। इदं। व
दामि। जुष्टं। देवेभिः। उत। मानुषेभिः। यं। कामये। तंऽतं। उग्रं। कृणोमि। तं। ब्रह्माणं। तं। ऋषिं। तं। सुऽमेधां।
३३॥ अहं। रुद्राय। धनुः। आ। तनोमि। ब्रह्मऽद्विषे। शरवे। हंतवै। ऊं इति। अहं। जनाय। सऽमदं। कृणोमि। अ
हं। द्यावापृथिवी इति। आ। विवेश। अहं। सुवे। पितरं। अस्य। मूर्द्धन्। मम। योनिः। अप्ऽसु। अंतः। इति।
समुद्रे। ततः। वि। तिष्ठे। भुवना। अनु। विश्वा। उत। अमूं। द्यां। वर्ष्मणा। उप। स्पृशामि। अहं। एव। वातःऽ
इव। प्र। वामि। आऽरभमाणा। भुवनानि। विश्वा। ०। एतावती। महिना। सं। बभूव॥ ३४॥ न। तं। अंहः। न।
दुःऽइतं। देवासः। अष्ट। मर्त्यं। सऽजोषसः। यं। अर्यमा। मित्रः। नयंति। वरुणः। अति। द्विषः। तत्। हि।

© Dharmartha Trust J&K. Digitized by eGangotri

वरुणमित्रार्यमनू॥

अ.प. वयं।वृणीमहे।०येन।निः।अंहसः।यूयं।पाथ।नेथ।च।मर्त्यं।अति।द्विषः।ते।नूनं।नः।अयं।ऊतये।०।नयिष्ठाः।
९० ऊं इति।नः।नेषणि।पर्षिष्ठाः।ऊं इति।नः।पर्षणि।अति।द्विषः।यूयं।विश्वं।परि।पाथ।०।युष्माकं।शर्म्मणि।
प्रिये।स्याम।सुऽप्रनीतयः।अति।द्विषः।आदित्यासः।अति।स्त्रिधः।०।तुग्रं।मरुत्ऽभिः।रुद्रं।हुवेम।इंद्रं।
90 अग्निं।स्वस्तये।अति।द्विषः।नेतारः।ऊं इति।सु।नः।तिरः।०।अति।विश्वानि।दुःऽइता।राजानः।चर्षणी
नां।अति।द्विषः।शुनं।अस्मभ्यं।ऊतये।०।शर्म्म।यच्छंतु।सऽप्रथः।आदित्यासः।यत्।ईमहे।अति।द्विषः।
यथा ह त्यद्व०।सवः ।०।।१३।।रात्री।वि।अख्यत्।आऽयती।पुरुऽत्रा।देवी।अक्षऽभिः।विश्वाः।अधि।श्रियः।अधित।आ।उरु।
अप्राः।अमर्त्या।निऽवतः।देवी।उत्ऽवतः।ज्योतिषा।बाधते।तमः।निः।ऊं इति।स्वसारं।अकृत।उषसं। ९०

© Dharmartha Trust J&K. Digitized by eGangotri

देवी। आऽयती। अप। इतः। कं। इति। हा। स्तने। तमः। सा। नः। अद्य। यस्याः। वयं। नि। ते। यामन्। अविक्ष्म हि। वृक्षे। न।
वसतिं। वयः। नि। ग्रामासः। अविक्षत। नि। पत्ऽवंतः। नि। पक्षिणः। नि। श्येनासः। चित्। अर्थिनः। पथया। वृक्यं।
वृकं। यवय। स्तेनं। ऊर्म्ये। अथ। नः। सुऽतरा। भव। उप। मा। पेपिशत्। तमः। रुक्मं। वि। अक्तं। अस्थित। उषः। ऋ-
णाःऽइव। यातय। उप। ते। गाःऽइव। आ। अकरं। वृणीष्व। दुहितः। दिवः। रात्रि। स्तोमं। न। जिग्युषे॥ १८॥ मम। अ-
ग्ने। वर्चः। विऽहवेषु। अस्तु। वयं। त्वा। इंधानाः। तन्वं। पुषेम। मह्यं। नमंतां। प्रऽदिशः। चतस्रः। त्वया। अधिऽअक्षे-
ण। पृतनाः। जयेम। मम। देवाः। विऽहवे। संतु। सर्वे। इंद्रऽवंतः। मरुतः। विष्णुः। अग्निः। मम। अंतरिक्षं। उरुऽलो-
कं। अस्तु। मह्यं। वातः। पवतां। कामे। अस्मिन्। मयि। देवाः। द्रविणं। आ। यजंतां। मयि। आऽशीः। अस्तु। मयि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ देवऽहूतिः। दैव्याः। होतारः। वनुषंत। पूर्वे। अरिष्टाः। स्याम। तन्वा। सुऽवीराः। मयि। यजंतु। मम। यानि। हव्या। आऽ
९१ कूतिः। सत्या। मनसः। मे। अस्तु। एनः। मा। नि। गां। कतमत्। चन। अहं। विश्वे। देवासः। अधि। वोचत। नः। दे
वीः। षट्। उर्वीः। उरु। नः। कृणोत। विश्वे। देवासः। इह। वीरयध्वं। मा। हास्महि। प्रऽजया। मा। तनूभिः। मा। रधा
म। द्विषते। सोम। राजन्॥३५॥ अग्ने। मन्युं। प्रतिऽनुदन्। परेषां। अदब्धः। गोपाः। परि। पाहि। नः। त्वं। प्रत्यंचः।
यंतु। निऽगुत्नः। पुनः। एति। ते। अमा। एषां। चित्तं। प्रऽबुधां। वि। नेशत्। धाता। धातॄणां। भुवनस्य। यः। पतिः। देवं।
त्रातारं। अभिमातिऽसहं। इमं। यज्ञं। अश्विना। उभा। बृहस्पतिः। देवाः। पांतु। यजमानं। निःऽअर्थात्। उरुऽव्य
चाः। नः। महिषः। शर्म। यंसत्। अस्मिन्। हवे। पुरुऽहूतः। पुरुऽक्षुः। सः। नः। प्रऽजायै। हरिऽअश्व। मृळय। इंद्र। ९६

© Dharmartha Trust J&K. Digitized by eGangotri

मा । नः । रिरिषः । मा । परा । दाः । ये । नः । सऽपत्नाः । अप । ते । भवंतु । इंद्राग्निऽभ्यां । अव । बाधामहे । तान् । वसवः ।
रुद्राः । आदित्याः । उपरिऽस्पृशं । मा । उग्रं । चेत्तारं । अधिऽराजं । अक्रन् । ९ ॥ न । असत् । आसीत् । नो इति । जं ।
सत् । आसीत् । तदानीं । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् । किं । आ । अवरीवरिति । कुह । क
स्य । शर्मन् । अंभः । किं । आसीत् । गहनं । गभीरं । न । मृत्युः । आसीत् । अमृतं । न । तर्हि । न । रात्र्याः । अह्नः ।
आसीत् । प्रऽकेतः । आनीत् । अवातं । स्वधया । तत् । एकं । तस्मात् । ह । अन्यत् । न । परः । किं । चन । आस । त
मः । आसीत् । तमसा । गूळ्हं । अग्रे । अप्रऽकेतं । सलिलं । सर्वं । आः । इदं । तुच्छ्येन । आभु । अपिऽहितं । य
त् । आसीत् । तपसः । तत् । महिना । अजायत । एकं । कामः । तत् । अग्रे । सं । अवर्तत । अधि । मनसः । रेतः ।

© Dharmartha Trust J&K. Digitized by eGangotri

१अ· प्रथमं।यत्।आसीत्।सतः।बंधुं।असति।निः।अविंदन्।हृदि।प्रतिऽइष्य।कवयः।मनीषा।तिरश्चीनः।विऽ
१२ ततः।रश्मिः।एषां।अधः।स्वित्।आसीत्।उपरि।स्वित्।आसीत्।रेतःऽधाः।आसन्।महिमानः।आसन्।
स्वधा।अवस्तात्।प्रऽयतिः।परस्तात्।०।कुतः।आऽजाता।कुतः।इयं।विऽसृष्टिः।अर्वाक्।देवाः।अस्य।
92 विऽसर्जनेन।अथ।कः।वेद।यतः।आऽबभूव।इयं।विऽसृष्टिः।यतः।आऽबभूव।यदि।वा।दधे।यदि।वा।न।
यः।अस्य।अधिऽअक्षः।परमे।विऽओमन्।सः।अंग।वेद।०।वेद।।७।।यः।यज्ञः।विश्वतः।तंतुऽभिः।ततः।
एकऽशतं।देवऽकर्मेभिः।आऽयतः।इमे।वयंति।पितरः।ये।आऽययुः।प्र।वय।अप।वय।इति।आसते।त
ते।पुमान्।एनं।तनुते।उत्।कृणत्ति।पुमान्।वि।तत्ने।अधि।नाके।अस्मिन्।इमे।मयूखाः।उप।सेदुः। १२

© Dharmartha Trust J&K. Digitized by eGangotri

ॐ इति। सदः। सामानि। चक्रुः। तसराणि। ओतवे। का। आसीत्। प्रऽमा। प्रतिऽमा। किं। निऽदानं। आज्यं। किं।
आसीत्। परिऽधिः। कः। आसीत्। छंदः। किं। आसीत्। प्रउगं। किं। उक्थं। यत्। देवाः। देवं। अयजंत। विश्वे।
अग्नेः। गायत्री। अभवत्। सऽयुग्वा। उष्णिहया। सविता। सं। बभूव। अनुऽस्तुभा। सोमः। उक्थैः। महस्वान्
। बृहस्पतेः। बृहती। वाचं। आवत्। विऽराट्। मित्रावरुणयोः। अभिऽश्रीः। इंद्रस्य। त्रिऽस्तुप्। इह। भागः। अन्हः
। विश्वान्। देवान्। जगती। आ। विवेश। तेन। चाक्लृप्रे। ऋषयः। मनुष्याः। चाक्लृप्रे। तेन। ऋषयः। मनुष्याः। य
ज्ञे। जाते। पितरः। नः। पुराणे। पश्यन्। मन्ये। मनसा। चक्षसा। तान्। ये। इमं। यज्ञं। अयजंत। पूर्वे। सहऽस्तो
माः। सहऽछंदसः। आऽवृतः। सहऽप्रमाः। ऋषयः। सप्त। दैव्याः। पूर्वेषां। पंथां। अनुऽदृश्य। धीराः। अनुऽआले

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ भिरे। रथ्यः। न। रश्मीन्॥ ३८॥ अप। प्राचः। इंद्र। विश्वान्। अमित्रान्। अप। अपाचः। अभिऽभूते। नुदस्व। अप।
९३ उदीचः। अप। शूर। अधराचः। उरौ। यथा। तव। शर्मन्। मदेम॥ कुवित्। अंग। यवऽमंतः। यवं। चित्। यथा। दां
93 ति। अनुऽपूर्वं। विऽयूय। इहऽइह। एषां। कृणुहि। भोजनानि। ये। बर्हिषः। नमःऽवृक्तिं। न। जग्मुः। न। हि। स्थूरि
ऋतुऽथा। यातं। अस्ति। न। उत। श्रवः। विविदे। संऽगमेषु।०। युवं। सुरामं। अश्विना। नमुचौ। आसुरे। सचा।
विऽपिपाना। शुभः। पती इति। इंद्रं। कर्मऽसु। आवतं। पुत्रंऽइव। पितरौ। अश्विना। उभा। इंद्र। आवथुः। काव्यैः।
दंसनाभिः। यत्। सुरामं। वि। अपिबः। शचीभिः। सरस्वती। त्वा। मघऽवन्। अभिष्णक्।०।।१९।। ईजानं।
इत्। द्यौः। गूर्तऽवसुः। ईजानं। भूमिः। अभि। प्रऽभूषणि। ईजानं। देवौ। अश्विनौ। अभि। सुम्नैः। अवर्द्धतां। ९३

© Dharmartha Trust J&K. Digitized by eGangotri

ना।वां।मित्रावरुणा।धारयत्क्षिती इति धारयत्ऽक्षिती।सुऽसुम्ना।इषितत्वता।यजामसि।युवोः।क्राणाय।स
ख्यैः।अभि।स्याम।रक्षसः।अधा।चित्।नु।यत्।दिधिषामहे।वां।अभि।प्रियं।रेक्णः।पत्यमानाः।दद्वान्।
वा।यत्।पुष्यति।रेक्णः।सं।ऊं इति।आरन्।नकिः।अस्य।मघानि।असौ।अन्यः।असुर।सूयत।द्यौः।०।
मूर्द्धा।रथस्य।चाकन्।न।एतावता।एनसा।अंतकऽध्रुक्।आस्मिन्।सु।एनत्।आऽशकः।पूर्तेः।एनः।हिते।मित्रे
।निःऽगता।न।हंति।वीरान्।अवोः।वा।यत्।धात्।तनूषु।अवः।प्रियासु।यज्ञियासु।अर्वा।युवोः।हि।मा
ता।अदितिः।विऽचेतसा।द्यौः।न।भूमिः।पयसा।पुपूतनि।अव।प्रिया।दिदिष्टन।सूरः।निनिक्त।रश्मिऽ
भिः।युवं।हि।अप्नःऽराजौ।असीदतं।तिष्ठत्।रथं।न।धूःऽसदं।वनऽसदा।तेना।नः।कणूकऽयंतीः।नृऽमेधः।

© Dharmartha Trust J&K. Digitized by eGangotri

प·अ· त्रात्रा। अंहसः। सुऽमेधः। त्रात्रा। अंहसः॥ २०॥ प्र। इति। सु। अस्मै। पुरःऽरथं। इंद्राय। शूषं। अर्चत। अभीके। चित्।
९४ ऊं इति। लोकऽकृत्। संऽगे। समत्ऽसु। वृत्रऽहा। अस्माकं। बोधि। चोदिता। नभंतां। अन्यकेषां। ज्याकाः।
94 अधि। धन्वऽसु। त्वं। सिंधून्। अव। असृजः। अधराचः। अहन्। अहिं। अशत्रुः। इंद्र। जज्ञिषे। विश्वं। पु
ष्यसि। वार्यं। तं। त्वा। परि। स्वजामहे॥०॥ वि। सु। विश्वाः। अरातयः। अर्यः। नशंत। नः। धियः। अस्ता। अ
वे। सि। शत्रवे। वधं। यः। नः। इंद्र। जिघांसति। या। ते। रातिः। ददिः। वसु॥०॥ यः। नः। इंद्र। अभितः। जनः। वृकऽयुः।
आऽदिदेशति। अधःऽपदं। तं। ईं। कृधि। विऽबाधः। असि। ससहिः॥०॥ अभि। दासति। सऽनाभिः। यः।
च। निष्ट्यः। अव। तस्य। बलं। तिर। महीऽइव। द्यौः। अध। त्मना॥०॥ सखिऽत्वं। आ। रभामहे। ऋतस्य। नः। ९४

© Dharmartha Trust J&K. Digitized by eGangotri

पथा। नय। अति। विश्वानि। दुःऽइता। ०। अस्मभ्यं। सु। त्वं। इंद्र। तां। शिक्ष। या। दोहते। प्रति। वरं। जरित्रे। अ

यं छिद्रऽऊध्नी। पीपयत्। यथा। नः। ०।। २३।। उभे इति। यत्। इंद्र। रोदसी इति। आ। पप्रथ। उषाःऽइव। महांतं।

त्वा। महीनां। संऽराजं। चर्षणीनां। देवी। जनित्री। अजीजनत्। भद्रा। जनित्री। अजीजनत्। अव। स्म।

अधस्पदं ०।। दुःऽहनायतः। मर्तस्य। तनुहि। स्थिरं। ०। अव। याः। बृहतीः। इषः। विश्वऽचंद्राः। अमित्रऽहन्। शचीभिः।

शक्र। धूनुहि। इंद्र। विश्वाभिः। ऊतिऽभिः। ०। अव। यत्। त्वं। शतक्रतो इति शतऽक्रतो। इंद्र। विश्वानि। धू

नुषे। रयिं। न। सुन्वते। सचा। सहस्रिणीभिः। ऊतिऽभिः। ०। अव। स्वेदाःऽइव। अभितः। विष्वक्। पतंतु।

दिद्यवः। दूर्वायाःऽइव। तंतवः। वि। अस्मत्। एतु। दुःऽमतिः। ०। दीर्घं। हि। अंकुशं। यथा। शक्तिं। बिभर्षि।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. मंतुऽमः। पूर्वेण। मघवन्। पदा। अजः। वयां। यथा। यमः।१०। नकिः। देवाः। मिनीमसि। नकिः। आ। योपयामसि।
९५ मंत्रऽश्रुत्यं। चरामसि। पक्षेभिः। अपिऽकक्षेभिः। अत्र। अभि। सं। रभामहे।११। यस्मिन्। वृक्षे। सुऽपलाशे।
देवैः। संऽपिबते। यमः। अत्र। नः। विश्पतिः। पिता। पुराणान्। अनु। वेनति। पुराणान्। अनुऽवेनंतं। चरंतं। पा
पया। अमुया। असूयन्। अभि। अचाकशं। तस्मै। अस्पृयेहे। पुनः। इति। यं। कुमार। नवं। रथं। अचक्रं। मनसा।
अकृणोः। एकऽईषं। विश्वतः। प्रांचं। अपश्यन्। अधि। तिष्ठसि। यं। कुमार। प्र। अवर्तयः। रथं। विप्रेभ्यः।
परि। तं। साम। अनु। प्र। अवर्त्तत। सं। इतः। नावि। आऽहितं। कः। कुमारं। अजनयत्। रथं। कः। निः। अव
र्तयत्। कः। स्वित्। तत्। अद्य। नः। ब्रूयात्। अनुऽदेयी। यथा। अभवत्। यथा। अभवत्। अनुऽदेयी। ततः। ९५

अग्रं। अजायत। पुरस्तात्। बुध्नः। आ। ततः। पश्चात्। निःऽअयनं। कृतं। इदं। यमस्य। सदनं। देवऽमानं। यत्। उ
च्यते। इयं। अस्य। धम्यते। नाळीः। अयं। गीःऽभिः। परिऽकृतः।। २४।। केशी। अग्निं। केशी। विषं। केशी। बिभर्ति।
रोदसी इति। केशी। विश्वं। स्वः। दृशे। केशी। इदं। ज्योतिः। उच्यते।। मुनयः। वातऽरशनाः। पिशंगाः। वसते। मला।
वातस्य। अनु। ध्राजिं। यंति। यत्। देवासः। अविक्षत।। उत्ऽमदिताः। मौनेयेन। वातान्। आ। तस्थिम। वयं। शरी
रा। इत्। अस्माकं। यूयं। मर्तासः। अभि। पश्यथ।। अंतरिक्षेण। पतति। विश्वा। रूपा। अवऽचाकशत्। मुनिः।
४ देवस्यऽदेवस्य। सौऽहृत्याय। सखा। हितः।। वातस्य। अश्वः। वायोः। सखा। अथो इति। देवऽइषितः। मुनिः। उ
भौ। समुद्रौ। आ। क्षेति। यः। च। पूर्वः। उत। अपरः।। अप्सरसां। गंधर्वाणां। मृगाणां। चरणे। चरन्। केशी। के

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ तस्य। विद्वान्। सखा। स्वादुः। मदिन्ऽतमः। वायुः। अस्मै। उप। अमंथत्। पिनष्टि। स्म। कुनंनमा। केशी। वि
९६ षस्य। पात्रेण। यत्। रुद्रेण। अपिबत्। सह। ॥ १५ ॥ उत। देवाः। अवऽहितं। देवाः। उत्। नयथ। पुनरिति। उत। आ
गः। चक्रुषं। देवाः। देवाः। जीवयथ। पुनरिति। द्वौ। इमौ। वातौ। वातः। आ। सिंधोः। आ। पराऽवतः। दक्षं। ते।
96 अन्यः। आ। वातु। परा। अन्यः। वातु। यत्। रपः। आ। वात। वाहि। भेषजं। वि। वात। वाहि। यत्। रपः। त्वं।
हि। विश्वऽभेषजः। देवानां। दूतः। ईयसे। आ। त्वा। अगमं। शंतातिऽभिः। अथो इति। अरिष्टतातिऽभिः। द
क्षं। ते। भद्रं। आ। अभार्षं। परा। यक्ष्मं। सुवामि। ते। त्रायंतां। इह। देवाः। त्रायतां। मरुतां। गणः। त्रायंतां।
विश्वा। भूतानि। यथा। अयं। अरपाः। असत्। आपः। इत्। वै। ऊं इति। भेषजीः। आपः। अमीवऽचातनीः ९६

© Dharmartha Trust J&K. Digitized by eGangotri

नीः। आपः। सर्वस्य। भेषजीः। ताः। ते। कृण्वंतु। भेषजं। हस्ताभ्यां। दशऽशाखाभ्यां। जिह्वा। वाचः। पुरःऽगवी।
अनामयित्नुऽभ्यां। त्वा। ताभ्यां। त्वा। उप। स्पृशामसि। २५। तव। त्ये। इंद्र। सख्येषु। वह्नयः। ऋतं। मन्वा
नाः। वि। अदर्दिरुः। वलं। यत्र। दशस्यन्। उषसः। रिणन्। अपः। कुत्साय। मन्मन्। अह्यः। च। दंसयः।
अव। असृजः। प्रऽस्रवः। श्वंचयः। गिरीन्। उत्। आजः। उस्राः। अपिबः। मधु। प्रियं। अवर्धयः। वनिनः। अ
स्य। दंससा। शुशोच। सूर्यः। ऋतऽजातया। गिरा। वि। सूर्यः। मध्ये। अमुचत्। रथं। दिवः। विदत्। दासा
य। प्रतिऽमानं। आर्यः। दृळ्हानि। पिप्रोः। असुरस्य। मायिनः। इंद्रः। वि। आस्यत्। चकृऽवान्। ऋजि
श्वना। अनाधृष्टानि। धृषितः। वि। आस्यत्। निऽधीन्। अदेवान्। अमृणत्। अयास्यः। मासा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ ऽइव। सूर्यः। वसुः। पुर्यां। आ। ददे। गृणानः। शत्रून्। अश्नणात्। विरुक्मता। अयुद्धऽसेनः। विऽभ्वा। विऽ
९८ भिंदता। दाशत्। वृत्रऽहा। तुज्यानि। तेजते। इंद्रस्य। वज्रात्। अबिभेत्। अभिऽश्नथः। प्र। अक्रामत्।
शुंध्यूः। अजहात्। उषाः। अनः। एता। स्या। ते। श्रुत्यानि। केवला। यत्। एकः। एकं। अकृणोः। अय
97 ज्ञं। मासां। विऽधानं। अदधाः। अधि। द्यवि। त्वया। विऽभिन्नं। भरति। प्रऽधिं। पिता। ॥२८॥ सूर्यऽ
रश्मिः। हरिऽकेशः। पुरस्तात्। सविता। ज्योतिः। उत्। अयान्। अजस्रं। तस्य। पूषा। प्रऽसवे। याति।
विद्वान्। संऽपश्यन्। विश्वा। भुवनानि। गोपाः। नृऽचक्षाः। एषः। दिवः। मध्ये। आस्ते। आऽपप्रिऽ
वान्। रोदसी इति। अंतरिक्षं। सः। विश्वाचीः। अभि। चष्टे। घृताचीः। अंतरा। पूर्वं। अपरं। च। केतुं। ९८

© Dharmartha Trust J&K. Digitized by eGangotri

०। विश्वा। रूपा। अभि। चष्टे। शचीभिः। ०। इंद्रः। न। तस्थौ। संऽअरे। धनानां। विश्वऽवसुं। सोम। गंधर्वं। आपः।
ददृशुषीः। तत्। ऋतेन। वि। आयन्। तत्। अनुऽअवैत्। इंद्रः। ररहाणः। आसां। परि। सूर्यस्य। परिऽधीन्।
अपश्यत्। विश्वऽवसुः। अभि। तत्। नः। गृणातु। दिव्यः। गंधर्वः। रजसः। विऽमानः। ०। धियः। हिन्वानः।
धियः। इत्। नः। अव्याः। सस्निं। अविंदत्। चरणे। नदीनां। अप। अवृणोत्। दुरः। अश्मऽव्रजानां। प्र।
आसां। गंधर्वः। अमृतानि। वोचत्। इंद्रः। दक्षं। परि। जानात्। अहीनां। २॥ अग्ने। तव। श्रवः। वयः। म
हि। भ्राजंते। अर्चयः। विभावसो इति विभाऽवसो। बृहद्भानो इति बृहत्ऽभानो। शवसा। वाजं। उक्थ्यं।
दधासि। दाशुषे। कवे। पावकऽवर्चाः। शुक्रऽवर्चाः। अनूनऽवर्चाः। उत्। इयर्षि। भानुना। पुत्रः। मात

© Dharmartha Trust J&K. Digitized by eGangotri

उभेइति॥

प॰अ॰ रो॥विऽचरन्॥उर्वा॥अवसि॥पृणक्षि॥रोदसीइति॥ऊर्जः॥नपात्॥जातऽवेदः॥सुशस्तिऽभिः॥मंदस्व॥धीतिऽ

१८ भिः॥हितः॥त्वेइति॥इषः॥सं॥दधुः॥भूरिऽवर्पसः॥चित्रऽऊतयः॥वामऽजाताः॥इरज्यन्॥अग्ने॥प्रथयस्व॥

जंतुऽभिः॥अस्मेइति॥रायः॥अमर्त्य॥सः॥दर्शतस्य॥वपुषः॥वि॥राजसि॥पृणक्षि॥सानसिं॥क्रतुं॥इष्क

र्तारं॥अध्वरस्य॥प्रऽचेतसं॥क्षयंतं॥राधसः॥महः॥रातिं॥वामस्य॥सुऽभगां॥महीं॥इषं॥दधासि॥सान

सिं॥रयिं॥ऋतऽवानं॥महिषं॥विश्वऽदर्शतं॥०॥श्रुत्ऽकर्णं॥सप्रथःऽतमं॥त्वा॥गिरा॥दैव्यं॥मानुषा॥युगा

॥२९॥अग्ने॥अच्छ॥वद॥इह॥नः॥प्रत्यङ्॥नः॥सुऽमनाः॥भव॥प्र॥नः॥यच्छ॥विशः॥पते॥धनऽदाः॥असि॥

नः॥त्वं॥प्र॥नः॥यच्छ॥अर्यमा॥प्र॥भगः॥प्र॥बृहस्पतिः॥प्र॥देवाः॥प्र॥उत॥सूनृता॥रायः॥देवी॥ददातु॥ १८

© Dharmartha Trust J&K. Digitized by eGangotri

नः। सोमं। राजानं। अवसे। अग्निं। गीःऽभिः। हवामहे। आदित्यान्। विष्णुं। सूर्य्यं। ब्रह्माणं। च। बृहस्पतिं। इं

द्रवायू। इति। बृहस्पतिं। सुऽहवा। इह। हवामहे। यथा। नः। सर्वः। इत्। जनः। संऽगत्यां। सुऽमनाः। असत्।

अर्य्यमणं। बृहस्पतिं। इंद्रं। दानाय। चोदय। वातं। विष्णुं। सरस्वतीं। सवितारं। च। वाजिनं। ०। अग्निऽ

भिः। ब्रह्मा। यज्ञं। च। वर्द्धय। त्वं। नः। देवऽतातये। रायः। दानाय। चोदय। २०। अयं। अग्ने। जरिता। त्वे

इति। अभूत्। अपि। सहसः। सूनो इति। नहि। अन्यत्। अस्ति। आप्यं। भद्रं। हि। शर्म्म। त्रिःऽवरूथं। अ

स्ति। ते। आरे। हिंसानां। अप। दिद्युं। आ। कृधि। प्रऽवत्। ते। अग्ने। जनिम। पितुऽयतः। साची। इव।

विश्वा। भुवना। नि। ऋंजसे। प्र। सप्तयः। प्र। सनिषंत। नः। धियः। पुरः। चरंति। पशुपाःऽइव। त्मना।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. उत।वै।ऊं इति।परि।वृणक्षि।बृस्पते।बृहो।अग्ने।उल्ल पस्या।स्वधाऽवः।उत।खिल्याः।उर्वराणां।भवंति
११ ।मा।ते।हेलिं।नविषी।चुकुधाम।यत्।उत्ऽवनेः।निऽवतः।यासि।बृहस्पते।पथहा।एषि।प्रगार्द्धिनीऽइ
99 षा।सेना।यदा।ते।०वत्ताःऽइवा।श्मश्रु।वपसि।प्रा।भूमा।प्रति।अस्या।श्रेणयः।दद्भ्रे।एकं।निऽयानं।ब
हवः।रथासः।बाहू इति।यत्।अग्ने।अनुऽमर्जानः।न्यङ्।उत्तानां।अनुऽएषि।भूमिं।उत्।ते।शुष्माः
।जिहानां।उत्।ते।अर्चिः।उत्।ते।अग्ने।शशमानस्य।वाजाः।उत्।श्वंचस्व।नि।नम।वर्धमानः।आ
त्वा।अद्य।विश्वे।वसवः।सदन्तु।अपां।इदं।निऽअयनं।समुद्रस्य।निऽवेशनं।अन्यं।कृणुष्व।इ
तः।पंथां।तेन।याहि।वशान्।अनु।आऽअयने।ते।पराऽअयने।दूर्वाः।रोहन्तु।पुष्पिणीः।ह्रदाः। ११

© Dharmartha Trust J&K. Digitized by eGangotri

चा। पुंडरीकाणि। समुद्रस्यागृहाः। इमे॥ ३ ॥ इत्यष्टमाष्टके सप्तमो ध्यायः॥ ॐ॥ मू॥ संवद् सो रव्यो
त्रिरा। श्विन मयं हिताक्ष्र्यं पुत्रः सुपर्णो। यामायनो वो र्ध्व रुशनो गायत्री। बृहती गायत्र्यौ सतोबृहती। वि
शारपंक्ति। रिमामिंद्राण्युपनिषत्। सपत्नीबाधनमानुष्टुभं तु पंक्त्यंतं। मरण्यान्यैरंमदो। देव मुनि ररण्यानी
तुष्टानं। अन्ते पंच सुवेदाः शैरीषिस्त्रिष्टुबंतं। सुबाणास पृथुर्वैन्यः। सवितार्च न्हैरण्य स्तूपः सावित्रं। समिद्धो
वा सिष्ठो मृळीकं। आग्नेयं बार्हतं। मं से दु परिष्टाज्ज्योतिष्मती। अग स्तुपां त्या वा। श्रद्ध्या श्रद्धा कामायिनी। आ
दू मानुष्टुभं तु। शासः शासो भारद्वाजं। इं द्र स्व यं तीर्दें द्रजा मय। इंद्र मातरो गायत्रं। सोमो यमी भावरन मा नु
ष्टुभं। स्वरायि शिंबिंगे भारद्वाजो। लक्ष्मीघ्नं। द्विती या तृतीया। आं सून णस्य से। अं त्या वैश्वदेव्य गिं के तु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ राग्नेय्य। आग्नेयं गायत्रं। मिमानुकं भुवन आप्त्यः साधनो वा भौवनो। वैश्वदेवं ह्यैपदं त्रैष्टुभं। सूर्यो न श्चु
१०० क्षुः सौर्यः सौर्यं गायत्रं। मुद सौषट्। पौलोमी शच्या। मानं तु श्या वानुष्टुभं। तीव्रस्य पंच पूरणो वैश्वामित्रो
100 मुंचामि त्वा प्राजापत्यो यक्ष्मनाशनो। राजयक्ष्मघ्नमं त्यानुष्टुप्पं। ब्रह्मणा षट् ब्राह्मो रक्षोहा। गर्भसंस्रा
वे प्रायश्चित्तमानुष्टुभं। अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्न। मपेहि पंच प्रचेता दुःस्वप्नघ्नं। पंक्त्यं
कपोतः लं त्रिष्टुप् मध्ये। देवा नैर्ऋतः कपोतो पहतौ प्रायश्चित्तं वैश्वदेवं। मृषभं मृषभो वैराजः। शाक्वरो वा स
पत्नघ्नं। मानुष्टुभं महापंक्तिः स्यं तं तु। म्येदं चेतुष्कं। विश्वामित्रजमदग्नी जागतं। तृतीया लिंगोक्तदेवता।
वातस्यानिलो वातायनो वायव्यं। मयोभूः शबरः काक्षीवतो गव्यं। विभ्राड्विभ्राट् सौर्यः सौर्यं जा १००

© Dharmartha Trust J&K. Digitized by eGangotri

गतं । मा स्तारपंचाग्र्यं तं । त्वं त्यमिटतो भार्गवो गायत्रं । मा या हिंसं वर्चनेकषस्यं द्वैपदं । मा त्वा षट् । ध्रुवो राज्ञस्तु
तिस्त्वानुष्टुभं । त्वभीवर्त्तेन पंचाभीवर्त्तः । प्रचश्चतुष्क । मूर्ध्वग्रावा बुधिग्राव्णोस्तोद्गाय । त्रं । प्रसस्नवः सूनु
रार्भवं । आग्नेयमानुष्टुभं । द्वितीया गायत्र्याद्या । अर्भवीपतं गंत्र चं पतंगः प्राजापत्यो मायाभेदं । जगत्यादि
त्रयमूष्वरिष्टनेमिस्ताक्ष्यस्तार्क्ष्यं । मुत्तिष्ठते कर्चो । शि[illegible]विरो शीनरः काशिराजः प्रतर्दनो । रोहिदश्वो व
सुमना आद्यानुष्टुप् । प्रससाहिषे जयरैंद्रं । प्रथः श्रैकर्चो । प्रथो वासिष्ठः सप्रथो भारद्वाजो । घर्मः सौ
र्यो वैश्वदेवं । बृहस्पतिस्तपुर्मूर्धा बार्हस्पत्यो बार्हस्पत्यं । मपश्यन्प्रजावान्प्राजापत्यो । न्व चं यज्ञमा
न पत्नी होत्राशिषो । विष्णुस्त्वष्टा गर्भकर्ता । विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिंगोक्तदेवतमानुष्टुभं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. महिस्तस्यधृतिर्वारुणिरादित्यंस्वस्त्ययनंगायत्रंवैयातोवातायनउलोवायव्यंप्राग्नयेपंचाग्नेयोवत्स

३०१ आग्नेयंतुप्रनूनंतरचमाग्नेयःश्येनोजातवेदस्यमायंगौःसार्पराज्ञात्मदैवतंसौर्यंवऋचमाधुच्छंदसो

घमर्षणोभाववृत्तमानुष्टुभंतुसंसंचतुष्कंसंवननःसंज्ञानमाद्याग्नेयीतृतीयात्रिष्टुप्तृतीयात्रि

ष्टुप्।।नदेतत्सूक्तंसहस्रंसप्तदशाकंसपादाधिकंऋग्वेदेपारायणपाठेशाकल्येशैशिरीयकेनमोब्र

ह्मणेनमोब्रह्मणेनमःशौनकायनमःशौनकाय।।९८।।इतिचतुष्षष्टिरनुक्रमणिका।।अष्टमाष्टकःस

माप्तः।।ॐम्र।।यं।चित्रा।अत्रिं।ऋतुं।उजुरं।अर्थ्यां।अश्वानां।यातवे।कक्षीवंतं।यदि।पुनरिति।रथं।

नारुणुथः।नवी।यं।चित्रा।अश्वानां।वाजिनं।अरेणवः।यं।अन्नं।ताट्टक्षं।ग्रं।थिं।ना।विं।स्यतं।अत्रिं। ३०१

© Dharmartha Trust J&K. Digitized by eGangotri

यविष्ठं। आ। रजः। नरा। दंसिष्ठौ। अत्रये। शुभ्रा। सिसासतं। धियः। अथ। हि। वां। दिवः। नरा। पुनरिति। स्तो
मः। न। विऽशसे। चिते। नत्। वां। सुऽराधसा। रातिः। सुऽमतिः। अश्विना। आ। यत्। नः। सदने। पृथौ। समने।
पर्षथः। नरा। युवं। भुज्युं। समुद्रे। आ। रजसः। पारे। ईंखितं। यातं। अच्छ। पतत्रिऽभिः। नासत्या। सातये। कृतं।
आ। वां। सुम्नैः। शंयू इवेति शंयूऽइव। मंहिष्ठा। विश्वऽवेदसा। सं। अस्मे इति। भूषतं। नरा। उत्सं। न। पिप्युषीः।
इषः। ३। अयं। हि। ते। अमर्त्यः। इंदुः। अत्यः। न। पत्यते। दक्षः। विश्वऽआयुः। वेधसे। अयं। अस्मासु। काव्यः।
ऋभुः। वज्रः। दास्वते। अयं। बिभर्ति। ऊर्ध्वऽकृशनं। मदं। ऋभुः। न। कृत्व्यं। मदं। घृषुः। श्येनाय। कृत्वने। आ
सु। स्वासु। वंसगः। अव। दीधेत्। अहीशुवः। यं। सुऽपर्णः। पराऽवतः। श्येनस्य। पुत्रः। आ। अभरत्। शतऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ चक्रं।यः।अश्वः।वर्तनिः।यं।ते।श्येनः।चारुं।अरुकं।पदा।आ।अभरत्।अरुणं।मानं।अंधसः।एना।वयः।वि।
१०२ तारि।आयुः।जीवसे।एना।जागार।बंधुता।एव।तत्।इंद्रः।इंदुना।देवेषु।चित्।धारयाते।महि।त्यजः।क्रत्वा।
०।सुक्रतो इति सुऽक्रतो।क्रत्वा।अयं।अस्मत्।आ।सुतनः॥३॥ इमां।खनामि।ओषधिं।वीरुधं।बलवत्ऽत
मां।यया।सऽपत्नीं।बाधते।यया।संऽविंदते।पतिं।उत्तानऽपर्णे।सुऽभगे।देवऽजूते।सहस्वति।सऽपत्नीं।मे।
परा।धम।पतिं।मे।केवलं।कुरु।उत्ऽतरा।अहं।उत्ऽतरे।उत्ऽतरा।इत्।उत्ऽतराभ्यः।अथ।सऽपत्नी।या।
मम।अधरा।सा।अधराभ्यः।नहि।अस्याः।नाम।गृभ्णामि।नो इति।अस्मिन्।रमते।जने।परां।एव।
पराऽवतं।सऽपत्नीं।गमयामसि।अहं।अस्मि।सहमाना।अथो।त्वं।असि।ससहिः।उभे इति।सहस्व १०२

© Dharmartha Trust J&K. Digitized by eGangotri

त्नीऽइति। मृळीः। सऽपत्नीं। मे। परा। वह॥ उप। ते। अधां। सहमानां। अभि। त्वा। अधां। सहीयसा। मां। अनु। प्र। ते।
मनः। वत्सं। गौःऽइव। धावतु। पथा। वाःऽइव। धावतु॥ ३॥ अरण्यानि। अरण्यानि। असौ। या। प्रऽइव। न
श्यसि। कथा। ग्रामं। न। पृच्छसि। न। त्वा। भीःऽइव। विंदती३ँ॥ वृषऽरवाय। वदते। यत्। उपऽअवति। चिच्चिकः। अ
आघाटिभिःऽइव। धावयन्। अरण्यानिः। महीयते॥ उत। गावःऽइव। अदंति। उत। वेश्मऽइव। दृश्यते। उतो इति। अ
रण्यानिः। सायं। शकटीःऽइव। सर्जति॥ गां। अंग। एषः। आ। ह्वयति। दारु। अंग। एषः। अप। अवधीत्। वस
न्। अरण्यान्यां। सायं। अक्रुक्षत्। इति। मन्यते॥ न। वै। अरण्यानिः। हंति। अन्यः। च। इत्। न। अभिऽगच्छ
ति। स्वादोः। फलस्य। जग्ध्वाय। यथाऽकामं। नि। पद्यते॥ आंजनऽगंधिं। सुरभिं। बहुऽअन्नां। अकृषिऽवलां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ प्र। अहं। मृगाणां। मातरं। अरण्यानिं। अशंसिषं॥ ६॥ श्रत्। ते। दधामि। प्रथमाय। मन्यवे। अहन्। यत्। वृत्रं।
१०३ नर्यं। विवेः। अपः। उभे इति। यत्। त्वा। भवतः। रोदसी इति। अनु। रेजते। शुष्मात्। पृथिवी। चित्। अद्रिवः।
त्वं। मायाभिः। अनवद्य। मायिनं। श्रवस्यता। मनसा। वृत्रं। अर्दयः। त्वां। इत्। नरः। वृणते। गोऽइष्टिषु। त्वां।
103 विश्वासु। हव्यासु। इष्टिषु। आ। एषु। चाकंधि। पुरुऽहूत। सूरिषु। वृधासः। ये। मघऽवन्। आनशुः। म
घं। अर्चन्ति। तोके। तनये। परिष्टिषु। मेधऽसाता। वाजिनं। अह्रये। धने। सः। इत्। नु। रायः। सुऽभृतस्य।
चाकनत्। मदं। यः। अस्य। रंह्यं। चिकेतति। त्वाऽवृधः। मघऽवन्। दाश्वऽअध्वरः। मक्षु। सः। वाजं। भरते।
धना। नृऽभिः। त्वां। शर्धाय। महिना। गृणानः। उरु। कृधि। मघऽवन्। शग्धि। रायः। त्वं। नः। मित्रः। वरुणः। १०३

© Dharmartha Trust J&K. Digitized by eGangotri

ना।मायी।पिर्वः।ना।दस्मा।दयसे।विऽभक्ता॥५॥सुस्वा।ना।सः।इंद्र।स्तुमसि।त्वा।ससऽवांसः।च।तुविऽ
नृम्ण।वाजं।आ।नः।भर।सुऽवितं।यस्य।चाकन्।त्मना।तना।सनुयाम।त्वाऽऊताः।ऋष्वः।त्वं।इंद्र।शू
र।जातः।०।बिभर्मासि।प्र।स्रवणेना।सोमं।अर्य्यः।वा।गिरः।अभि।अर्च्च।विद्वान्।ऋषीणां।विप्रः।सु
ऽमतिं।चकानः।ते।स्याम।ये।रणयंत।सोमैः।एना।तुना।तुभ्यं।रथऽओह्ला।भक्षैः।इमा।ब्रह्मा।इंद्र।तु
भ्यं।शंसि।दाः।नृभ्यः।नृणां।शूर।शवः।तेभिः।भव।सऽक्रतुः।येषु।चाकन्।उत।त्रायस्व।गृणत॥४॥
उत।स्त्तीन्।श्रुधि।हवं।इंद्र।शूर।पृथ्याः।उत।स्तवसे।वेन्यस्य।अर्कैः।आ।यः।ते।योनिं।घृतऽवंतं।अ
स्वाः।ऊर्मिः।न।निम्नैः।द्रवयंत।वक्काः॥५॥सविता।यंत्रैः।पृथिवीं।अरम्णात्।अस्कंभने।सवि

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ ता। यां। अदृंहत्। अश्वंऽइव। अधुक्षत्। धुनिं। अंतरिक्षं। अतूर्ते। बद्धं। सविता। समुद्रं। यत्र। समुद्रः।
३०४ स्कभितः। वि। औनत्। अपां। नपात्। सविता। तस्य। वेद। अतः। भूः। अतः। आःऽउत्थितं। रजः। अतः। द्या
वापृथिवी इति। अप्रथेतां। पश्चा। इदं। अन्यत्। अभवत्। यजत्रं। अमर्त्यस्य। भुवनस्य। भूना। सुऽ
104 पर्ण्णः। अंग। सवितुः। गरुत्मान्। पूर्वः। जातः। सः। ऊं इति। अस्य। अनु। धर्म्म। गाःऽइव। ग्रामं। युयु व
धिःऽइव। अश्वान्। वाश्राऽइव। वत्सं। सुऽमनाः। दुहाना। पतिःऽइव। जायां। अभि। नः। नि। एतु। धर्ता
र्ता। दिवः। सविता। विश्वऽवारः। हिरण्यऽस्तूपः। सवितः। यथा। त्वा। आंगिरसः। जुहे। वाजे। अस्मि
न्। एव। त्वा। अर्चन्। अवसे। वंदमानः। सोमस्यऽइव। अंशुं। प्रति। जागर। अहं। ७॥ संऽइद्धः। १०४

© Dharmartha Trust J&K. Digitized by eGangotri

चित्रा। सं। इध्यसे। देवेभ्यः। हव्यऽवाहन। आदित्यैः। रुद्रैः। वसुऽभिः। नः। आ। गहि। मृळीकाय। नः। आ। गहि।
ऽमर्त्यासः। त्वा। संऽइधानं। हवामहे। मृळीकाय। हवामहे। त्वां। ऊं इति। आ। नः। वैदसं। विश्वऽवारं। गृणे। धि
या। अग्ने। देवान्। आ। वह। नः। प्रियऽव्रतान्। मृळीकाय। प्रियऽव्रतान्। अग्निः। देवः। देवानां। अभव
त्। पुरःऽहितः। अग्निं। मनुष्याः। ऋषयः। सं। ईधिरे। अग्निं। महः। धनऽसातौ। अहं। हुवे। मृळीकं। धनऽ
सातये। अग्निः। अत्रिं। भरत्ऽवाजं। गविष्ठिरं। प्र। आवत्। नः। कण्वं। त्रसदस्युं। आऽहवे। अग्निं। वसि
ष्ठः। हवते। पुरःऽहितः। मृळीकाय। पुरःऽहितः॥ ॥ श्रद्धया। अग्निः। सं। इध्यते। श्रद्धया। हूयते। हविः।
श्रद्धां। भगस्य। मूर्धनि। वचसा। आ। वेदयामसि। प्रियं। श्रद्धे। ददतः। प्रियं। श्रद्धे। दिदासतः। प्रियं।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. भोजेषु। यज्वऽसु। इदं। मे। उदितं। कृधि। यथा। देवाः। असुरेषु। श्रद्धां। उग्रेषु। चक्रिरे। एवं। भोजेषु। यज्वऽसु।
३०५ अस्माकं। उदितं। कृधि। श्रद्धां। देवाः। यजमानाः। वायुऽगोपाः। उप। आसते। श्रद्धां। हृदय्यया। आऽकूत्या।
श्रद्धया। विंदते। वसु। श्रद्धां। प्रातः। हवामहे। श्रद्धां। मध्यंदिनं। परि। श्रद्धां। सूर्यस्य। निऽम्रुचि। श्रद्धे। श्र
105 त्। धापय। इह। नः॥ १॥ शासः। इत्था। महान्। असि। अमित्रऽखादः। अद्भुतः। न। यस्य। हन्यते। सखा।
न। जीयते। कदा। चन। स्वस्तिऽदाः। विशः। पतिः। वृत्रऽहा। विऽमृधः। वशी। वृषा। इंद्रः। पुरः। एतु। नः। सोमऽ
पाः। अभयंऽकरः। वि। रक्षः। वि। मृधः। जहि। वि। वृत्रस्य। हनू इति। रुज। वि। मन्युं। इंद्र। वृत्रऽहन्। अमित्र
स्य। अभिऽदासतः। वि। नः। इंद्र। मृधः। जहि। नीचा। यच्छ। पृतन्यतः। यः। अस्मान्। अभिऽदासति। अध ३०५

© Dharmartha Trust J&K. Digitized by eGangotri

रांगमया । तमः । अप । इंद्र । द्विषतः । मनः । अप । जिज्यासतः । वधं । वि । मन्योः । शर्म । यच्छ । वरीयः । यवय । वधं ॥ १० ॥
ईंखयंतीः । अपस्युवः । इंद्रं । जातं । उप । आसते । भेजानासः । सुऽवीर्यं । त्वं । इंद्र । बलात् । अधि । सहसः । जातः ।
ओजसः । त्वं । वृषन् । वृषा । इत् । असि । त्वं । इंद्र । असि । वृत्रऽहा । वि । अंतरिक्षं । अतिरः । उत् । द्यां । अस्तभ्नाः ।
ओजसा । त्वं । इंद्र । सऽजोषसं । अर्कं । बिभर्षि । बाह्वोः । वज्रं । शिशानः । ओजसा । त्वं । इंद्र । अभिऽभूः । असि
। विश्वा । जातानि । ओजसा । सः । विश्वाः । भुवः । आ । अभवः ॥ ११ ॥ सोमः । एकेभ्यः । पवते । घृतं । एके । उप ।
आसते । येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् । तपसा । ये । अनाधृष्याः । तपसा । ये ।
स्वः । ययुः । तपः । ये । चक्रिरे । महः । ० । ये । युध्यंते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः । ये । वा । सहस्रऽदक्षिणाः । ०

© Dharmartha Trust J&K. Digitized by eGangotri

पु॰अ॰ ।ये।चित्।पूर्वे।ऋतऽसापः।ऋतऽवानः।ऋतऽवृधः।पितॄन्।तपस्वतः।यम।०।सहस्रऽनीथाः।कवयः।ये।
१०६ गोपायंति।सूर्यं।ऋषीन्।तपस्वतः।यम।तपःऽजान्।अपि।गच्छतात्।।१२।।अरायि।काणे।विऽकटे।
गिरिं।गच्छ।सदान्वे।शिरिंबिठस्य।सत्वऽभिः।तेभिः।त्वा।चातयामसि।चत्तो इति।इतः।चत्तो।अमुतः।
106 सर्वा।भ्रूणानि।आरुषी।अराय्यं।ब्रह्मणः।पते।तीक्ष्णऽशृंग।उत्ऽऋषन्।इहि।अदः।यत्।दारु।प्लवते।
सिंधोः।पारे।अपूरुषं।तत्।आ।रभस्व।दुर्हनो इति दुःऽहनो।तेन।गच्छ।परःऽतरं।यत्।ह।प्राचीः।अ
जगंत।उरः।मंडूरऽधाणिकीः।हताः।इंद्रस्य।शत्रवः।सर्वे।बुद्बुद्ऽयाशवः।परि।इमे।गां।अनेषत।परि। द
अग्निं।अहृषत।देवेषु।अक्रत।श्रवः।कः।इमान्।आ।दधर्षति।।१३।।अग्निं।हिन्वंतु।नः।धियः।स १०६

© Dharmartha Trust J&K. Digitized by eGangotri

त्रिं। आ। भुं। इव। आ। जिष्णु। तेन। जेष्म। धनं ऽ धनं। यया। गाः। आ ऽ करामहे। सेनया। अग्ने। तव। ऊत्या। तो। [illegible]। नः।
हिन्व। मघत्तये। आ। अग्ने। स्थूरं। रयिं। भर। पृथुं। गो ऽ मंतं। अश्विनं। अङ्धि। खं। वर्तय। पणिं। अग्ने। नक्षत्रं।
अजरं। आ। सूर्यं। रोहयः। दिवि। दधत्। ज्योतिः। जनेभ्यः। अग्ने। केतुः। विशां। असि। प्रेष्ठः। श्रेष्ठः। उपस्थ ऽ
सत्। बोध। स्तोत्रे। वयः। दधत्॥१४॥ इमा। नु। कं। भुवना। सीसधाम। इंद्रः। च। विश्वे। च। देवाः। यज्ञं। च।
नः। तन्वं। च। प्र ऽ जां। च। आदित्यैः। इंद्रः। सह। चीक्लृपाति। आदित्यैः। इंद्रः। स ऽ गणः। मरुत् ऽ भिः। अस्माकं।
भूतु। अविता। तनूनां। हत्वाय। देवाः। असुरान्। आयत्। आयन्। देवाः। देव ऽ त्वं। अभि ऽ रक्षमाणाः। प्रत्यंचं।
अर्कं। अनयन्। शचीभिः॥०॥१५॥ सूर्यः। नः। दिवः। पातु। वातः। अंतरिक्षात्। अग्निः। नः। पार्थिवेभ्यः।

© Dharmartha Trust J&K. Digitized by eGangotri

१·अ· जोषं।सवितः।यस्य।ते।हरः।शतं।सवान्।अर्हति।पाहि।नः।दिद्युतः।पतंत्याः।चक्षुः।नः।देवः।सविता।
३०७ चक्षुः।नः।उत।पर्वतः।चक्षुः।धाता।दधातु।नः।चक्षुः।नः।धेहि।चक्षुषे।चक्षुः।वि॰ख्यै।तनूभ्यः।सं।
च।इदं।वि।च।पश्येम।०।वि।पश्येम।न॰चक्षसः॥१६॥उत्।असौ।सूर्य्यः।अगात्।उत्।अयं।मा
मकः।भगः।अहं।तत्।विद्वला।पतिं।अभि।असाक्षि।वि॰सससहिः।अहं।केतुः।अहं।मूर्द्धा।अ
हं।उग्रा।वि॰वाचनी।मम।इत्।अनु।क्रतुं।पतिः।सेहानायाः।उप॰आचरेत्।मम।पुत्राः।शत्रु॰ह
नः।अथो।इति।मे।दुहिता।वि॰राट्।उत।अहं।अस्मि।सं॰जया।पत्यौ।मे।श्लोकः।उत्॰तमः।ये
न।इंद्रः।हविषा।कृत्वी।अभवत्।द्युम्नी।उत्॰तमः।इदं।तत्।अक्रि।देवाः।असपत्ना।किल।अ ३०८

© Dharmartha Trust J&K. Digitized by eGangotri

भुवं। अस॒पत्ना। सपत्न॒ऽघ्नी। जयंती। अभिऽभूवरी। आ। अरक्षं। अन्यासां। वर्चः। राधः। अस्थेयसां।
ऽइव। सं। अजैषं। इमाः। अहं। सऽपत्नीः। अभिऽभूवरी। यथा। अहं। अस्य। वीरस्य। विऽराजानि। ज
नस्य। च॥१७॥ तीव्रस्य। अभिऽवयसः। अस्य। पाहि। सर्व्वऽरथा। विऽहरी इति। इह। मुंच। इंद्र। मा।
वा। यजमानाः। सः। अन्ये। निऽरीरमन्। तुभ्यं। इमे। सुताः। सः। तुभ्यं। सुताः। तुभ्यं। ऊं इति। सो। त्वा। सः।
वां। गिरः। श्वात्र्याः। आ। ह्वयंति। इंद्र। इदं। अद्य। सवनं। जुषाणः। विश्वस्य। विद्वान्। इह। पाहि।
सोमं। यः। उशता। मनसा। सोमं। अस्मै। सर्वऽहृदा। देवऽकामः। सुनोति। न। गाः। इंद्रः। तस्य। परा।
ददाति। प्रऽशस्तं। इत्। चारुं। अस्मै। कृणोति। अनुऽस्पष्टः। भवति। एषः। अस्य। यः। अस्मै। रेवान्।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. ना।सुनोति।सोमं।निः।अरत्नौ।मघऽवा।तं।दधाति।ब्रह्मऽद्विषः।हंति।अननुऽदिष्टः।अश्वऽयंतः।
१०८ ।गव्यंतः।वाजयंतः।हवामहे।त्वा।उपऽगंतवै।ऊं इति।आऽभूषंतः।त्वा।सुऽमतौ।नवायां।वयं।
इंद्र।त्वा।शुनं।हुवेम।।१८।।मुंचामि।त्वा।हविषा।जीवनाय।कं।अज्ञातऽयक्ष्मात्।उत।राजऽ
108 यक्ष्मात्।ग्राहिः।जग्राह।यदि।वा।एतत्।एनं।तस्याः।इंद्राग्नी इति।प्र।मुमुक्तं।एनं।यदि।क्षितऽ
आयुः।यदि।वा।पराऽइतः।यदि।मृत्योः।अंतिकं।निःऽइतः।एव।तं।आ।हरामि।निःऽऋतेः।उ
हृ पऽस्थात्।अस्पार्षं।एनं।शतऽशारदाय।सहस्रऽअक्षेण।शतऽशारदेन।शतऽआयुषा।हवि
षा।आ।अहार्षं।एनं।शतं।यथा।इमं।शरदः।नयाति।इंद्रः।विश्वस्य।दुःऽइतस्य।पारं।शतं। १०८

© Dharmartha Trust J&K. Digitized by eGangotri

जीव।शरदः।वर्द्धमानः।शतं।हेमंतान्।शतं।ऊं इति।वसंतान्।शतं।इंद्राग्नी इति।सविता।बृहस्पतिः।शतं
आयुषा।हविषा।इमं।पुनः।दुः।आ।अहार्षं।त्वा।अविदं।त्वा।पुनः।आ।अगाः।पुनःऽनव।सर्वऽअंग।
सर्वं।ते।चक्षुः।सर्वं।आयुः।च।ते।अविदं।।३।।ब्रह्मणा।अग्निः।संऽविदानः।रक्षःऽहा।बाधतां।इतः।अ
मीवा।यः।ते।गर्भं।दुःऽनामा।योनिं।आऽशये।०।अमीवा।०।अग्निः।तं।ब्रह्मणा।सह।निः।क्रव्यऽअदं।
अनीनशत्।यः।ते।हंति।पतयंतं।निऽसत्स्नुं।यः।सरीसृपं।जातं।यः।ते।जिघांसति।तं।इतः।इतः।
नाशयामसि।यः।ते।ऊरू इति।विऽहरति।अंतरा।दंपती इति दंऽपती।शये।योनिं।यः।अंतः।आऽ
रेळ्हि।०।यः।त्वा।भ्राता।पतिः।भूत्वा।जारः।भूत्वा।निऽपद्यते।प्रऽजां।०।यः।त्वा।स्वप्नेन।तमसा।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ मोहयित्वा। निऽपद्यते।०॥२०॥ अक्षीभ्यां। ते। नासिकाभ्यां। कर्णाभ्यां। छुबुकात्। अधि। यक्ष्मं। शीर्षण्यं।
१०९ मस्तिष्कात्। जिह्वायाः। वि। वृहामि। ते। ग्रीवाभ्यः। ते। उष्णिहाभ्यः। कीकसाभ्यः। अनूक्यात्। यक्ष्मं।
दोषण्यं। असाभ्यां। बाहुऽभ्यां।०। आंत्रेभ्यः। ते। गुदाभ्यः। वनिष्ठोः। हृदयात्। अधि। यक्ष्मं। मतस्नाभ्यां।
109 यक्नः। प्लाशिऽभ्यः।०। ऊरुऽभ्यां। ते। अष्ठीवत्ऽभ्यां। पार्ष्णिऽभ्यां। प्रऽपदाभ्यां। यक्ष्मं। श्रोणिऽभ्यां। भासदा
त्। भंससः।०। मेहनात्। वनंऽकरणात्। लोमऽभ्यः। ते। नखेभ्यः। यक्ष्मं। सर्वस्मात्। आत्मनः। तं। इदं।
त ०। अंगात्ऽअंगात्। लोम्नःऽलोम्नः। जातं। पर्वणिऽपर्वणि।०॥२१॥ अप। इहि। मनसः। पते। अप। क्रा
म। परः। चर। परः। निःऽऋत्यै। आ। चक्ष्व। बहुधा। जीवतः। मनः। भद्रं। वै। वरं। वृणते। भद्रं। युंजंति। द १०९

© Dharmartha Trust J&K. Digitized by eGangotri

क्षिणं। भद्रं। वै। वस्व। ते। चक्षुः। बहुऽत्रा। जीवतः। मनः। यत्र। आऽश्वासः। निःऽश्वासः। अभिऽश्वासः। उपऽआरिम।
जाग्रतः। यत्र। स्वपंतः। अग्निः। विश्वानि। अपऽदुःऽकृतानि। अजुष्टानि। आरे। अस्मत्। दधातु। यत्र।
इंद्र। ब्रह्मणः। पते। अभिऽद्रोहं। चरामसि। प्रऽचेताः। नः। आंगिरसः। द्विषतां। पातु। अंहसः। ०। जाग्रत्ऽ
स्वप्नः। संऽकल्पः। पापः। यं। द्विष्मः। तं। सः। ऋच्छतु। यः। नः। द्वेष्टि। तं। ऋच्छतु। २२। देवाः। कपोतः। इषि
तः। यत्। इच्छन्। दूतः। निःऽऋत्याः। इदं। आऽजगाम। तस्मै। अर्चाम। कृणवाम। निःऽकृतिं। शं। नः। अस्तु।
द्विऽपदे। शं। चतुःऽपदे। शिवः। कपोतः। इषितः। नः। अस्तु। अनागाः। देवाः। शकुनः। गृहेषु। अग्निः। हि।
विप्रः। जुषतां। हविः। नः। परि। हेतिः। पक्षिणी। नः। वृणक्तु। हेतिः। पक्षिणी। नादभाति। अस्मान्। आ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ ह्यां। पदं। कृणुते। अग्निऽधाने। शं। नः। गोभ्यः। पुरुषेभ्यः। च। अस्तु। मा। नः। हिंसीत्। इह। देवाः। कपोतः।
११० यत्। उलूकः। वदति। मोघं। एतत्। यत्। कपोतः। पदं। अग्नौ। कृणोति। यस्य। दूतः। प्रऽहितः। एषः। ए
तत्। तस्मै। यमाय। नमः। अस्तु। मृत्यवे। ऋचा। कपोतं। नुदत। प्रऽनोदं। इषं। मदंतः। परि। गां। नय
110 ध्वं। संऽयोपयंतः। दुःऽइतानि। विश्वा। हित्वा। नः। ऊर्जं। प्र। पतात्। पतिष्ठः। ॥२३॥ ऋषभं। मा। स
मानानां। सऽपत्नानां। विऽससहिं। हंतारं। शत्रूणां। कृधि। विऽराजं। गोऽपतिं। गवां। अहं। अ
स्मि। सपत्नऽहा। इंद्रःऽइव। अरिष्टः। अक्षतः। अधः। सऽपत्नाः। मे। पदोः। इमे। सर्वे। अभिऽस्थि
ताः। अत्र। एव। वः। अपि। नह्यामि। उभे इति। आर्त्नीइवेत्यार्त्नीऽइव। ज्यया। वाचः। पते। नि। सेध। ११०

व:।

© Dharmartha Trust J&K. Digitized by eGangotri

इमाः। त्वा। यथा। मत्। अधरां। वदान्। अभिऽभूः। अहं। आ। अगां। विश्वऽकर्मणा। धाम्ना। आ। वः। चि
त्तं। आ। वः। व्रतं। आ। वः। अहं। संऽइतिं। ददे। योगऽक्षेमं। वः। आऽदाय। अहं। भूयासं। उत्ऽतमः।
आ। वः। मूर्द्धानं। अक्रमीं। अधःऽपदात्। मा। उत्। वदत। मंडूकाःऽइव। उदकात्। मंडूकाः। उदका
त्ऽइव। २४॥ तुभ्यं। इदं। इंद्र। परि। सिच्यते। मधु। त्वं। सुतस्य। कलशस्य। राजसि। त्वं। रयिं।
पुरुऽवीरां। ऊं इति। नः। कृधि। त्वं। तपः। परिऽतप्य। अजयः। स्व३रिति स्वः। स्वःऽजितं। महि।
मंदानं। अंधसः। हवामहे। परि। शक्रं। सुतान्। उप। इमं। नः। यज्ञं। इह। बोधि। आ। गहि। स्प
धः। जयंतं। मघऽवानं। ईमहे। सोमस्य। राज्ञः। वरुणस्य। धर्मणि। बृहस्पतेः। अनुऽमत्याः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ ऊं इति। शर्म्मणि। तव। अहं। अद्य। मघऽवन्। उपऽस्तुतौ। धातः। विधातरिति विऽधातः। कलशान्। अभ
३३३ क्षयं। प्रऽसूतः। भक्षं। अकरं। चरौ। अपि। स्तोमं। च। इमं। प्रथमः। सूरिः। उत्। मृजे। सुते। साते। मा। य
दि। आ। अगमं। वां। प्रति। विश्वामित्रजमदग्नीइति। दमे।।२५।। वातस्य। नु। महिमानं। रथस्य।
रुजन्। एति। स्तनयन्। अस्य। घोषः। दिविऽस्पृक्। याति। अरुणानि। कृण्वन्। उतो इति। एति।
पृथिव्याः। रेणुं। अस्यन्। सं। प्र। ईरते। अनु। वातस्य। विऽस्थाः। आ। एनं। गच्छंति। समनं। ना।
योषाः। ताभिः। सऽयुक्। सऽरथं। देवः। ईयते। अस्य। विश्वस्य। भुवनस्य। राजा। अंतरिक्षे। प
थिऽभिः। ईयमानः। न। नि। विशते। कतमत्। चन। अहरिति। अपां। सखा। प्रथमऽजाः। ऋतऽ ३३३

वा।क्वा।स्वित्।जातः।कुतः।आ।बभूव।आत्मा।देवानां।भुवनस्य।गर्भः।यथाऽवशं।चरति।देवः।ए
षः।घोषाः।इत्।अस्य।शृण्विरे।न।रूपं।तस्मै।वाताय।हविषा।विधेम।२४।मयःऽभूः।वातः।
अभि।वातु।उस्राः।ऊर्जस्वतीः।ओषधीः।आ।रिशंतां।पीवस्वतीः।जीवऽधन्याः।पिबंतु।अव
साय।पत्ऽवते।रुद्र।मृळय।सऽरूपाः।विऽरूपाः।एकऽरूपाः।यासां।अग्निः।इष्ट्या।नामा
नि।वेद।याः।अंगिरसः।तपसा।इह।चक्रुः।ताभ्यः।पर्जन्य।महि।शर्म।यच्छ।याः।देवेषु।तन्वं।
ऐरयंत।यासां।सोमः।विश्वा।रूपाणि।वेद।प्रजाऽवतीः।इंद्र।गोऽस्थे।रिरीहि।प्रजाऽपतिः।म
ह्यं।एताः।रराणः।विश्वैः।देवैः।पितृऽभिः।संऽविदानः।शिवाः।सतीः।उप।नः।गोऽस्थं।आ।अक

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ रियंकः।तासौ।वयं।प्रऽजया।सं।स्वदेम॥२९॥ विऽभ्राट्।बृहत्।पिबतु।सोम्यं।मधु।आयुः।दधत्।
३३२ यज्ञऽपतौ।अविऽह्रुतं।वातऽजूतः।यः।अभिऽरक्षति।त्मना।प्रऽजाः।पुपोष।पुरुधा।वि।राजति।विऽभ्रा
ट्।बृहत्।सुऽभृतं।वाजऽसातमं।धर्मन्।दिवः।धरुणे।सत्यं।अर्प्पितं।अमित्रऽहा।वृत्रऽहा।दस्यु
हन्ऽतमं।ज्योतिः।जज्ञे।असुरऽहा।सपत्नऽहा।०।उत्ऽतमं।विश्वऽजित्।धनऽजित्।उच्यते।बृह
त्।विश्वऽभ्राट्।भ्राजः।महि।सूर्य्यः।दृशे।उरु।पप्रथे।सहः।ओजः।अच्युतं।०।येन।इमा।विश्वा।
भुवनानि।आऽभृता।विश्वऽकर्म्मणा।विश्वदेव्यऽवता॥२[illegible]॥ त्वं।यं।इट्टतः।रथं।इंद्र।प्र।आवः।
सुतऽवंतः।अश्रणोः।सोमिनः।हवं।त्वं।मखस्य।दोधतः।शिरः।अव।त्वचः।भरः।अगच्छः।सोमि ३३२

112

© Dharmartha Trust J&K. Digitized by eGangotri

नः।गृहे।सखां।यां।इंद्रं।सखीं।आस्नः॥शुष्माय।वेन्यां।मुहुः।अश्वाः।मनस्य।वै।स्वयं।पश्वा।संनौ।पुरः।क्रु
धि।देवानां।चित्रा।तिरः।वशां॥१४॥आ।याहि।वनसा।सह।गावः।सचंत।वर्त्तनिं।यत्।ऊधऽभिः।
आ।याहि।वस्व्या।धिया।मंहिष्ठः।जारयत्ऽमखः।सुदानुऽभिः।पितुऽभृतः।न।तंतुं।इत्।सुऽ
दानवः।प्रति।दध्मः।यजामसि।उषाः।अप।स्वसुः।तमः।सं।वर्त्तयति।वर्त्तनिं।सुऽजातता।
॥१५॥आ।त्वा।अहार्षं।अंतः।एधि।ध्रुवः।तिष्ठ।अविऽचाचलिः।विशः।त्वा।सर्वाः।वांछंतु।मा।
त्वत्।राष्ट्रं।अधि।भ्रशत्।इह।एव।एधि।मा।अप।च्योष्ठाः।पर्वतःऽइव।अविऽचाचलिः।इं
द्रःऽइव।इह।ध्रुवः।तिष्ठ।इह।राष्ट्रं।ऊं।इति।धारय।इमं।इंद्रः।अदीधरत्।ध्रुवं।ध्रुवेण।हविषा।

© Dharmartha Trust J&K. Digitized by eGangotri

प.अ. तस्मै। सोमः। अधि। ब्रवत्। तस्मै। ऊं इति। ब्रह्मणः। पतिः। ध्रुवा। द्यौः। ध्रुवा। पृथिवी। ध्रुवासः। पर्वताः
११२ इमे। ध्रुवं। विश्वं। इदं। जगत्। ध्रुवः। राजा। विशां। अयं। ध्रुवं। ते। राजा। वरुणः। ध्रुवं। देवः। बृहस्प
तिः। ध्रुवं। ते। इंद्रः। च। अग्निः। च। राष्ट्रं। धारयतां। ध्रुवं। ध्रुवं। ध्रुवेण। हविषा। अभि। सोमं। मृ
113 शामसि। अथो इति। ते। इंद्रः। केवलीः। विशः। बलिऽहृतः। करत्॥ ३३॥ अभिऽवर्तेन। हविषा।
येन। इंद्रः। अभिऽववृते। तेन। अस्मान्। ब्रह्मणः। पते। अभि। राष्ट्राय। वर्तय। अभिऽवृत्य।
सऽपत्नान्। अभि। याः। नः। अरातयः। अभि। पृतन्यंतं। तिष्ठ। अभि। यः। नः। इरस्यति। अभि।
त्वा। देवः। सविता। अभि। सोमः। अवीवृतत्। अभि। त्वा। विश्वा। भूतानि। अभिऽवर्तः। यथा। ११२

© Dharmartha Trust J&K. Digitized by eGangotri

असं।सि।०।असपत्नः।किल।अभुवं।असपत्नः।सपत्नऽहा।अभिऽराष्ट्रः।विऽससहिः।यथा।अहं।
एषां।भूतानां।०।।३२।।प्र।वः।ग्रावाणः।सविता।देवः।सुवतु।धर्म्मणा।धूःऽसु।युज्यध्वं।सुनु
त।ग्रावाणः।अप।दुछ्,नां।अप।सेधत।दुःऽमतिं।उस्राः।कर्त्तन।भेषजं।ग्रावाणः।उपरिषु।आ।
महीयते।सऽजोषसः।वृष्णे।दधतः।वृष्ण्यं।ग्रावाणः।सविता।नु।वः।०।यजमानाय।सुन्वते।
।।३३।।प्र।सूनवः।ऋभूणां।बृहत्।नवंत।वृजना।क्षामा।ये।विश्वऽधायसः।अश्नन्।धेनुं।न।
मातरं।प्र।देवं।देव्या।धिया।भरत।जातऽवेदसं।हव्या।नः।वक्षत्।आनुषक्।अयं।ऊं इति।स्यः।
प्र।देवऽयुः।होता।यज्ञाय।नीयते।रथः।न।योः।अभिऽवृतः।घृणिऽवान्।चेतति।त्मना।अयं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ अग्निः।उरुष्यति।अमर्तात्ऽइव।जन्मनः।सहसः।चित्।सहीयान्।देवः।जीवातवे।कृतः॥३४॥पतं
३३५ गं।अक्तं।असुरस्य।मायया।हृदा।पश्यंति।मनसा।विपःऽचितः।समुद्रे।अंतरिति।कवयः।वि।
चक्षते।मरीचीनां।पदं।इच्छंति।वेधसः।पतंगः।वाचं।मनसा।बिभर्ति।तां।गंधर्वः।अवदत्।
114 गर्भे।अंतरिति।तां।द्योतमानां।स्वर्यं।मनीषां।ऋतस्य।पदे।कवयः।नि।पांति॥३५॥त्यं।ऊं इति।
सु।वाजिनं।देवऽजूतं।सहःऽवानं।तरुतारं।रथानां।अरिष्टऽनेमिं।पृतनाजं।आशुं।स्वस्तये।ता
र्क्ष्यं।इह।हुवेम।इंद्रस्यऽइव।रातिं।आऽजोहुवानाः।स्वस्तये।नावंऽइव।आ।रुहेम।उर्वी इति।पृथ्वी इति।
इति।बहुले इति।गभीरे इति।मा।वां।आऽइतौ।मा।पराऽइतौ।रिषाम।सद्यः।चित्।यः।शवसा।पं ११५

© Dharmartha Trust J&K. Digitized by eGangotri

च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान । सहस्रऽसाः । शतऽसाः । अस्य । रंहिः । न । स्म । वरंते । युव

तिं । न । शर्य्यां ॥ ३ ॥ उत् । तिष्ठत । अव । पश्यत । इंद्रस्य । भागं । ऋत्वियं । यदि । श्रातः । जुहोतन । यदि ।

अश्रातः । ममत्तन । श्रातं । हविः । ओ इति । सु । इंद्र । प्र । याहि । जगाम । सूरः । अध्वनः । विऽमध्यं । परि ।

त्वा । आसते । निधिऽभिः । सखायः । कुलऽपाः । न । व्राजऽपतिं । चरंतं । श्रातं । मन्ये । ऊधनि । श्रातं ।

अग्नौ । सुऽश्रातं । मन्ये । तत् । ऋतं । नवीयः । माध्यंदिनस्य । सवनस्य । दध्नः । पिब । इंद्र । वज्रिन् ।

पुरुऽकृत् । जुषाणः ॥ ३ ॥ प्र । ससहिषे । पुरुऽहूत । शत्रून् । ज्येष्ठः । ते । शुष्मः । इह । रातिः । अस्तु । इंद्र ।

आ । भर । दक्षिणेन । वसूनि । पतिः । सिंधूनां । असि । रेवतीनां । ० । पराऽवनः । आ । जगंथ । परस्याः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सऽकं। संऽशाय। पविं। इंद्र। तिग्मं। वि। शत्रून्। ताळ्हि। वि। मृधः। नुदस्व। इंद्र। क्षत्रं। अभि। वामं। ओजः।
११५ अजायथाः। वृषभ। चर्षणीनां। अप। अनुदः। जनं। अमित्रऽयंतं। उरुं। देवेभ्यः। अकृणोः। ऊं इति। लो
कं।।२७।। प्रथः। च। यस्य। सऽप्रथः। च। नाम। आनुऽस्तुभस्य। हविषः। हविः। यत्। धातुः। द्युतानात्।
सवितुः। च। विष्णोः। रथंऽतरं। आ। जभार। वसिष्ठः। अविंदन्। ते। अतिऽहितं। यत्। आसीत्।
यज्ञस्य। धाम। परमं। गुहा। यत्।०। भरत्ऽवाजः। बृहत्। आ। चक्रे। अग्नेः। ते। अविंदन्। मन
सा। दीध्यानाः। यजुः। स्कन्नं। प्रथमं। देवऽयानं।०। आ। सूर्यात्। अभरन्। घर्मं। एते।।२८।।
बृहस्पतिः। नयतु। दुःऽगहा। तिरः। पुनः। नेषत्। अघऽशंसाय। मन्म। क्षिपत्। अशस्तिं। अप। ११५

115

© Dharmartha Trust J&K. Digitized by eGangotri

दुःऽमतिं। हन्न्। अथ। करत। यजमानाय। शं। योः। नराशंसः। नः। अवतु। प्रऽयाजे। ०। अनुऽयाजः। हवेषु।
०। तपुः। मूर्द्धा। तपतु। रक्षसः। यो। ब्रह्मऽद्विषः। शरवे। हंतवे। ऊं। इलि। ०। ५०। अपश्यं। त्वा। मनसा। चे
कितानं। तपसः। जातं। तपसः। विऽभूतं। इह। प्रऽजां। इह। रयिं। रराणः। प्रजायस्व। प्रऽजया। पुत्रऽ
काम। ०। दीध्यानां। त्वा। यां। तन्वृ। इति। ऋत्व्ये। नाधमानां। उप। मां। उच्चा। युवतिः। बभूयाः। ०। पुत्रऽ
कामे। अहं। गर्भं। अदधां। ओषधीषु। अहं। विश्वेषु। भुवनेषु। अंतरिति। अहं। प्रऽजाः। अजन
यं। पृथिव्यां। अहं। जनिऽभ्यः। अपरीषु। पुत्रान्। ५१। विष्णुः। योनिं। कल्पयतु। त्वष्टा। रूपाणि।
पिंशतु। आ। सिंचतु। प्रजाऽपतिः। धाता। गर्भं। दधातु। ते। गर्भं। धेहि। सिनीवालि। गर्भं। धेहि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ सरस्वति। गर्भ्भं। ते। अश्विनौ। देवौ। आ। धत्तां। पुष्करऽस्रजा। हिरण्ययी इति। अरणी इति। यं। निःऽमंथतः।
११६ अश्विना। तं। ते। गर्भ्भं। हवामहे। दशमे। मासि। सूतवे। ५२। महि। त्रीणां। अवः। अस्तु। द्युक्षं। मित्र
स्य। अर्य्यम्णः। दुःऽआधर्षं। वरुणस्य। नहि। तेषां। अमा। चन। न। अध्वऽसु। वारणेषु। ईशे। रिपुः। अ
116 घऽशंसः। यस्मै। पुत्रासः। अदितेः। प्र। जीवसे। मर्त्याय। ज्योतिः। यच्छंति। अजस्रं। ५३। वातः। आ। वा
तु। भेषजं। शंऽभु। मयःऽभु। नः। हृदे। प्र। नः। आयूंषि। तारिषत्। उत। वात। पिता। असि। नः। उत। भ्रा
ता। उत। नः। सखा। सः। नः। जीवातवे। कृधि। यत्। अदः। वात। ते। गृहे। अमृतस्य। निऽधिः। हितः। त
तः। नः। देहि। जीवसे। ५४। प्र। अग्नये। वाचं। ईरय। वृषभाय। क्षितीनां। सः। नः। पर्षत्। अति। द्विषः। ११६

© Dharmartha Trust J&K. Digitized by eGangotri

यः। परस्याः। पराऽवतः। तिरः। धन्व। अतिऽरोचते।०। यः। रक्षांसि। निऽजूर्वति। वृषा। शुक्रेण। शोचिषा।०।
यः। अस्य। पारे। रजसः। शुक्रः। अग्निः। अजायत।०।।४५।। प्र। नूनं। जातऽवेदसं। अश्वं। हिनोत। वा
जिनं।०। अस्य। प्र। जातऽवेदसः। विप्रऽवीरस्य। मीळ्हुषः। महीं। इयर्मि। सुऽस्तुतिं। याः। रुचः। जातऽवे
दसः। देवऽत्रा। हव्यऽवाहनीः। ताभिः। नः। यज्ञं। इन्वतु।।४६।। आ। अयं। गौः। पृश्निः। अक्रमीत्। अस
दत्। मातरं। पुरः। पितरं। च। प्रऽयन्। स्वरिति स्वः। अंतः। चरति। रोचना। अस्य। प्राणात्। अपऽ
अनती। वि। अख्यत्। महिषः। दिवं। त्रिंशत्। धाम। वि। राजति। वाक्। पतंगाय। धीयते। प्रति। वस्तोः।
अह। द्युऽभिः।।४७।। ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत।। ततो रात्र्यजायत ततः समुद्रो अर्णवः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ समुद्रादर्णवादधिसंवत्सरोअजायत।।अहोरात्राणिविदधद्विश्वस्यमिषतोवशी।।सूर्याचंद्रमसौ

३३८ धातायथापूर्वमकल्पयत्।।दिवंचपृथिवींचांतरिक्षमथोस्वः।।४८।।संसं।इत्।युवसे।वृषन्।

117 अग्ने।विश्वानि।अर्यः।आ।इळः।पदे।सं।इध्यसे।सः।नः।वसूनि।आ।भर।सं।गछध्वं।सं।वद

ध्वं।सं।वः।मनांसि।जानतां।देवाः।भागं।यथा।पूर्वे।संऽजानानाः।उपऽआसते।समानः।मंत्रः।

संऽइतिः।समानी।समानं।मनः।सह।चित्तं।एषां।समानं।मंत्रं।अभि।मंत्रये।वः।समानेन।

वः।हविषा।जुहोमि।समानी।वः।आऽकूतिः।समाना।हृदयानि।वः।समानं।अस्तु।वः।मनः।

यथा।वः।सुऽसह।असति।।४९।।इतिअष्टमाष्टकेअष्टमोध्यायःसमाप्तः।। ५।। ७।। ७।। १९०

© Dharmartha Trust J&K. Digitized by eGangotri

प॰अ॰ श्रीकाशीविश्वेश्वरार्पणमस्तु ॥ ० ॥ शुद्धानि रम्याणि परिस्फुटानि पदानि ऋग्वेदभवानि संति ॥ त्रि
११८ विचार्य सम्यक् लिखितानि मानुना परोपकारार्थमथो स्वसिद्ध्यै ॥ १ ॥ वैराज आरभ्य उभाउन्
नं पर्यंतमादौ लिखितं गृहे च ॥ यत्रार्थमुद्दिश्य गतेन काश्यां कृतास्समाप्तिः पदपुस्तकस्य ॥ २ ॥
118 शके १७५५ किलकनाम संवत्सरे ॥ फाल्गुने मासे शुक्लपक्षे षष्ठ्यां तिथौ गुरुवासरे ॥ ०
इदं पुस्तकं समाप्तं ॥ गुर्जरोपकनामक रामचंद्रात्मजक पुरुषोत्तमेन लिखितं ॥ ० ॥ ० ॥
श्रीकृष्णार्पणमस्तु ॥ ० ॥ ० ॥ गोपालकृष्णार्पणमस्तु ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥

११८

© Dharmartha Trust J&K. Digitized by eGangotri

॥इतिपदेंअष्टमाष्टकः समाप्तः॥

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. श्रीगणेशायनमः॥हरिःॐ॥म॥प्रणोयास्यःसपस्वास्तगंनयासोमःपंचकविर्भार्गवस्त्वंत्वा
१ पवस्वोन्नेभुष्मासउचथ्योध्वर्योपरिद्युक्षउन्नेचतुक्कमवत्सारोस्यप्रत्नांयवंयवंपरिसोमःप्र
तेधारास्तरःसपवस्वप्रगायत्रेणोपांसापुरउष्णिगयावीतीत्रिंशदमहीयुरेतेअस्तगंज
मदग्निरापवस्वनिध्रुविःकाश्यपोवृषासोमकश्यपः॥ ॥ॐम॥प्रानुःइंदोइलि।मुहो।तनो।क्रु
र्मिं।नाबिभ्रत्।अर्षन्ति।अभिदेवान्।अयास्यः।मतीजुष्टः।धिया।हितः।सोमः।हिन्वे।पुरः।व
ति।विप्रस्य।धारया।कुविः।अयं।देवेषु।जागृविः।सुतः।एति।पवित्रे।आ।सोमः।याति।विचर्ष
णिः।सः।नः।पवस्व।राजः।युगं।चक्राणः।चारुं।अध्वरं।बर्हिष्मान्।आ।विवासति।सः।नः।भगा ३

© Dharmartha Trust J&K. Digitized by eGangotri

याः। वायवे। चित्रः। वीरः। सदाऽवृधः। सोमः। देवेषु। आ। यमत्। सः। नः। अद्य। वसुऽत्तये। क्रतुऽवित्। गातुऽवि
त्ऽतमः। वाजं। जेषि। श्रवः। बृहत्॥३॥ सः। पवस्व। मदाय। कं। नृऽचक्षाः। देवऽवीतये। इंदो इति। इंद्राय।
पीतये। सः। नः। अर्ष। अभि। दूत्यं। त्वां। इंद्राय। तोशसे। देवान्। सखिऽभ्यः। आ। वरं। उत। त्वां। अरुणं। वयं।
गोभिः। अंजमः। मदाय। कं। वि। नः। राये। दुरः। वृधि। अति। ऊं इति। पवित्रं। अक्रमीत्। वाजी। धुरं। न। या
मनि। इंदुः। देवेषु। पत्यते। सं। ईं। सखायः। अस्वरन्। वने। क्रीळंतं। अतिऽअविं। इंदुं। नावाः। अभि।
व्रता। तया। पवस्व। धारया। यया। पीतः। विऽचक्षसे। इंदो इति। स्तोत्रे। सुऽवीर्यं॥ ४॥ अस्मऽयन्। देवऽ
वीतये। अस्य। सः। रुत्व्याःऽइव। अक्षरं। तः। पर्वतेऽस्थाः। परिऽस्कृतासः। इंदवः। योषाऽइव। पित्र्यऽवती।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ वायुं। सोमाः। असृक्षत। एते। सोमासः। इंदवः। प्रयस्वंतः। चमूइति। सुताः। इंद्रं। वर्धंति। कर्मऽभिः। आ।
२ धावत। सुऽहस्त्यः। शुक्रा। गृभ्णीत। मंथिना। गोभिः। श्रीणीत। मत्सरं। सः। पवस्व। धनंऽजय। प्रऽयं
ता। राधसः। महः। अस्मभ्यं। सोम। गातुऽवित्। एतं। मृजंति। मर्ज्यं। पवमानं। दश। क्षिपः। इंद्राय। मत्सरं।
मदं। ३। अया। सोमः। सुऽकृत्यया। महः। चित्। अभि। अवर्धत। मंदानः। उत्। वृषऽयते। कृतानि। इत्।
अस्य। कर्त्वा। चेतंते। दस्युऽतर्हणा। ऋणा। च। धृष्णुः। चयते। आत्। सोमः। इंद्रियः। रसः। वज्रः। सहस्र
ऽसाः। भुवत्। उक्थं। यत्। अस्य। जायते। स्वयं। कविः। विऽधर्तरि। विप्राय। रत्नं। इच्छति। यदि। मर्मृ
ज्यते। धियः। सिसासतुः। रयीणां। वाजेषु। अर्वतांऽइव। भरेषु। जिग्युषां। असि। ४। तं। त्वा। नृ २

© Dharmartha Trust J&K. Digitized by eGangotri

म्णानि। बिभ्रतं। सधऽस्थेषु। महः। दिवः। चारुं। सुऽकृत्यया। ईमहे। संवृक्तऽधृष्णुं। उक्थ्यं। महाऽमहिव्र
तं। मदं। शतं। पुरः। रुरुक्षणिं। अतः। त्वा। रयिं। अभि। राजानं। सुक्रतो इति सुऽक्रतो। दिवः। सुऽपर्णः।
अव्यथिः। भरत्। आ। विश्वस्मै। इत्। स्वःऽदृशे। साधारणं। रजःऽतुरं। गोपां। ऋतस्य। विः। भरत्। अध। हि।
त्वा। नः। इन्द्रियं। ज्यायः। महिऽत्वं। आनशे। अभिष्टिऽकृत्। विऽचर्षणिः॥५॥ पवस्व। वृष्टिं। आ। सु। नः।
अपां। ऊर्मिं। दिवः। परि। अयक्ष्माः। बृहतीः। इषः। तया। पवस्व। धारया। यया। गावः। इह। आऽ
गमन्। जन्यासः। उप। नः। गृहं। घृतं। पवस्व। धारया। यज्ञेषु। देवऽवीतमः। अस्मभ्यं। वृष्टिं। आ। प
वस्व। नः। ऊर्जे। वि। अव्यये। पवित्रे। धाव। धारया। देवासः। शृणवन्। हि। कं। पवमानः। असिस्य

© Dharmartha Trust J&K. Digitized by eGangotri

आपवस्व मदिंतम पवित्रं धारया कवे। अर्कस्य योनिमासदं।

प॰स॰ द्त्। रक्षांसि। अपघ्नंपनत्। प्रत्नः वत्। रोचयन्। रुचः। दा। उत। ते। शुष्मा। सः। ईरते। सिंधोः। ऊर्मेः। इव। स्व
२ नः। वाणस्य। चोदय। पविं। प्रः स्वनो। ते। उत्। ईरते। तिस्रः। वाचः। मखस्युवः। यत्। अव्यो। एषि। सानवि। अ
व्यः। वारे। परि। प्रियं। हरिं। हिन्वंति। अद्रिभिः। पवमानं। मधुश्चुतं॥६॥ सः। पवस्व। मदिन्तम। गोभिः।
अंजानः। अक्तुभिः। इंदो इति। इंद्राय। पीतये॥७॥ अध्वर्यो इति। अद्रिभिः। सुतं। सोमं। पवित्रे। आ। सृज।
पुनीहि। इंद्राय। पातवे। दिवः। पीयूषं। उत्तमं। सोमं। इंद्राय। वज्रिणे। सुनोत। मधुमत्तमं। नवात्यो इं न
दो इति। अंधसः। देवाः। मधोः। वि। अश्नते। पवमानस्य। मरुतः। त्वं। हि। सोम। वर्द्धयन्। सुतः। मदाय। भूर्णी
ये। वृषन्। स्तोतारं। ऊतये। अभि। अर्ष। विचक्षण। पवित्रं। धारया। सुतः। अभि। वाजं। उत। श्रवः॥८॥ ३

© Dharmartha Trust J&K. Digitized by eGangotri

परि। सुवानः। सनत्ऽरयिः। भरत्। वाजं। नः। अंधसा। सुवानः। अर्षा। पवित्रे। आ। तव। स्लेभिः। अध्वऽभिः।
अव्यः। वारैः। परि। प्रियः। सहस्रऽधारः। यातः। तना। चरुः। यः। नः। तं। ईंखय। इंदो इति। नः। दानं। ईंखय। वधैः।
वधस्नो इति वधऽस्नो। ईंखय। नि। शुष्मं। इंदो इति। एषां। पुरुऽहूत। जनानां। यः। अस्मान्। आऽदिदेशति।
शतं। नः। इंदो इति। ऊतिऽभिः। सहस्रं। वा। शुचीनां। पवस्व। मंहयत्ऽरयिः॥ २॥ उत्। त्वा। शुष्मासः। अस्थुः।
रक्षः। भिंदंतः। अद्रिऽवः। नुदस्व। याः। परिऽस्पृधः। अया। निऽजघ्निः। ओजसा। रथऽसंगे। धने। हिते। स्तवै।
अबिभ्युषा। हृदा। अस्य। व्रतानि। न। आऽधृषे। पवमानस्य। दुःऽध्या। रुज। यः। त्वा। पृतन्यति। तं। हिन्वं-
ति। मदऽच्युतं। हरिं। नदीषु। वाजिनं। इंदुं। इंद्राय। मत्सरं॥ ३॥ अस्य। व्रतानि। अनु। द्युतं। शुक्रं। दुदुहे। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ ह्रयः। पयः। सहस्रऽसां। ऋषिं। अयं। सूर्यःऽइव। उपऽदृक्। अयं। सरांसि। धावति। सप्त। प्रऽवतः। आ। दि-
४ वं। अयं। विश्वानि। तिष्ठति। पुनानः। भुवना। उपरि। सोमः। देवः। न। सूर्यः। परि। नः। देवऽवीतये। वाजान्।
अर्षसि। गोऽमतः। पुनानः। इंदो इति। इंद्रऽयुः॥३॥ यवंऽयवं। नः। अंधसा। पुष्टंऽपुष्टं। परि। स्रव। सोम।
५ विश्वा। च। सोम। सौभगा। इंदो इति। यथा। तव। स्तवः। यथा। ते। जातं। अंधसः। नि। बर्हिषि। प्रिये। सदः। उत। नः।
गोऽवित्। अश्वऽवित्। पवस्व। सोम। अंधसा। मक्षु। तमेभिः। अहऽभिः। यः। जिनाति। न। जीयते। हंति।
शत्रुं। अभिऽइत्य। सः। पवस्व। सहस्रऽजित्॥३॥ परि। सोमः। ऋतं। बृहत्। आशुः। पवित्रे। अर्षति। वि-
घ्नन्। रक्षांसि। देवऽयुः। यत्। सोमः। वाजं। अर्षति। शतं। धाराः। अपस्युवः। इंद्रस्य। सख्यं। आऽविशन्। ४

© Dharmartha Trust J&K. Digitized by eGangotri

अभि । त्वा । योषणः । दश । जारं । न । कन्या । अनूषत । मृज्यसे । सोम । सातये । त्वां । इंद्राय । विष्णवे । स्वादुः ।
इंदो इति । परि । स्रव । नॄन् । स्तोतॄन् । पाहि । अंहसः ॥ १३ ॥ प्र । ते । धाराः । असश्चतः । दिवः । न । यंति । वृ-
ष्टयः । अच्छ । वाजं । सहस्रिणं । अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति । हरिः । तुंजानः । आयु-
धा । सः । मर्मृजानः । आयुऽभिः । इभः । राजाऽइव । सुऽव्रतः । श्येनः । न । वंसु । सीदति । सः । नः । विश्वा । दि-
वः । वसु । उतो इति । पृथिव्याः । अधि । पुनानः । इंदो इति । आ । भर ॥ १४ ॥ तरत् । सः । मंदी । धावति । धारा ।
सुतस्य । अंधसः । ० । उस्रा । वेद । वसूनां । मर्तस्य । देवी । अवसः । ० । ध्वस्रयोः । पुरुऽसंत्योः । आ । सह-
स्राणि । दद्महे । ० । आ । ययोः । त्रिंशतं । तना । सहस्राणि । च । दद्महे । ० ॥ १५ ॥ पवस्व । गोऽजित् । अश्वऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ जित्।विश्वं।जित्।सोम।रण्य।जित्।प्रजाः।वत्।रत्नं।आ।भर।पवस्व।अद्भ्यः।अदाभ्यः।पवस्व।
५ ओषधीभ्यः।पवस्व।धिषणाभ्यः।त्वं।सोम।पवमानः।विश्वानि।दुः।इला।तरा।कविः।सीद।नि।बर्हि
षि।पवमानः।स्वः।विदः।जायमानः।अभवः।महान्।इंदो।इति।विश्वान्।अभि।इत्।असि।३॥प्रगा
यत्रेण।गायत।पवमानं।विचर्षणिं।इंदुं।सहस्रचक्षसं।तं।वा।सहस्रचक्षसं।अथो।इति।सह
स्रभर्णसं।अति।वारं।अपाविषुः।अति।वारान्।पवमानः।असिस्यदत्।कलशान्।अभि।धावति।
इंद्रस्य।हार्दि।आविशन्।इंद्रस्य।सोम।राधसे।शं।पवस्व।विचर्षणे।प्रजाः।वत्।रेतः।आ।भर।३।७॥
अया।नीती।परि।स्रव।यः।ते।इंदो।इति।मदेषु।आ।अवाः।अहन्।नवतीः।नव।पुरः।सद्यः।इत्था।धि ५

धिये। दिवःऽदासाय। शंबरं। अध। त्यं। तुर्वशं। यदुं। परि। नः। अश्वं। अश्वऽवित्। गोऽमत्। इंदो इति।
हिरण्यऽवत्। अक्षरा। सहस्रिणीः। इषः। पवमानस्य। ते। वयं। पवित्रं। अभिऽउंदतः। सखिऽत्वं। आ।
वृणीमहे। ये। ते। पवित्रं। ऊर्मयः। अभिऽक्षरंति। धारया। तेभिः। नः। सोम। मृळय। १८। सः। नः। पु
नानः। आ। भर। रयिं। वीरऽवतीं। इषं। ईशानः। सोम। विश्वतः। एतं। ऊं इति। त्यं। दश। क्षिपः। मृजं
ति। सिंधुऽमातरं। सं। आदित्येभिः। अख्यत। सं। इंद्रेण। उत। वायुना। सुतः। एति। पवित्रे। आ। सं।
सूर्यस्य। रश्मिऽभिः। सः। नः। भगाय। वायवे। पूष्णे। पवस्व। मधुऽमान्। चारुः। मित्रे। वरुणे। च।
उच्चा। ते। जातं। अंधसः। दिवि। सत्। भूमिः। आ। ददे। उग्रं। शर्म। महि। श्रवः। १९। एना। विश्वानि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ अर्यः। आ। द्युम्नानि। मानुषाणां। सिषासंतः। वनामहे। सः। नः। इंद्राय। यज्यवे। वरुणाय। मरुत्ऽ
६ भ्यः। वरिवःऽवित्। परि। स्रव। उपोइति। सुऽजातं। अपऽसुरं। गोभिः। भंगं। परिऽकृतं। इंदुं। देवाः। अ
यासिषुः। तं। इत्। वर्द्धंतु। नः। गिरः। वत्सं। संशिश्वरीःऽइव। यः। इंद्रस्य। हृदंऽसनिः। अर्ष। नः। सोम।
शं। गवे। धुक्षस्व। पिप्युषीं। इषं। वर्द्ध। समुद्रं। उक्थ्यं॥ २०॥ पवमानः। अजीजनत्। दिवः। चित्रं।
न। तन्यतुं। ज्योतिः। वैश्वानरं। बृहत्। पवमानस्य। ते। रसः। मदः। राजन्। अदुच्छुनः। वि। वारं। अ
व्यं। अर्षति। पवमान। रसः। तव। दक्षः। वि[illegible]। वि। राजति। द्युऽमान्। ज्योतिः। विश्वं। स्वः। दृशे
। यः। ते। मदः। वरेण्यः। तेन। पवस्व। अंधसा। देवऽअवीः। अघशंसऽहा। जघ्निः। रक्षः। अमित्रियं। ६

© Dharmartha Trust J&K. Digitized by eGangotri

सास्निः। वाजं। दिवेऽदिवे। गोऽसाः। ऊं इति। अश्वऽसाः। असि॥ २१॥ संऽमिश्लः। अरुषः। भव। सुऽउपस्थाभिः
। न। धेनुऽभिः। सीदन्। श्येनः। न। योनिं। आ॥ सः। पवस्व। यः। आविथ। इंद्रं। वृत्राय। हंतवे। वव्रिऽवांसं।
महीः। अपः॥ सुऽवीरासः। वयं। धना। जयेम। सोम। मीढ्वः॥ पुनानः। वर्द्ध। नः। गिरः॥ त्वाऽऊताः। सः। तव।
अवसा। स्याम। वन्वंतः। आऽमुरः॥ सोम। व्रतेषु। जागृहि॥ अपऽघ्नन्। पवते। मृधः। अप। सोमः। अ
राव्णः। गच्छन्। इंद्रस्य। निःऽकृतं॥ २२॥ महः। नः। रायः। आ। भर। पवमान। जहि। मृधः। रास्व। इंदो
इति। वीरऽवत्। यशः॥ न। त्वा। शतं। चन। ह्रुतः। राधः। दित्संतं। आ। मिनन्। यत्। पुनानः। मखस्यसे॥
पवस्व। इंदो इति। वृषा। सुतः। कृधि। नः। यशसः। जने॥ विश्वाः। अप। द्विषः। जहि॥ अस्य। ते। सख्ये।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ वयं। तव। इंदो इति। द्युम्नेषु। उत्ऽतमाः। ससह्याम। पृतन्यतः। या। ते। भीमानि। आयुधा। तिग्मानि। संति।
७ धूर्वणे। रक्षः। समस्य। नः। निदः। रक्ष। एते। अस्रग्रं। इंदवः। तिरः। पवित्रं। आशवः। विश्वानि। अभि। सौ
भगा। वि ऽघ्नंतः। दुः ऽइता। पुरु। सुऽगा। तोकाय। वाजिनः। तना। कृण्वंतः। अर्वते। कृण्वंतः। वरिवः। गवे। अ
भि। अर्षति। सुऽस्तुतिं। इषं। अस्मभ्यं। सं ऽयतं। असावि। अंशुः। मदाय। अप्ऽसु। दक्षः। गिरि ऽस्थाः।
श्येनः। न। योनिं। आ। असदत्। शुभ्रं। अंधः। देवऽवीतं। अप्ऽसु। धूतः। नृऽभिः। सुतः। स्वदंति। गावः। प
यःऽभिः। रघा। आत्। ईं। अश्वं। न। हेतारः। अशूशुभन्। अमृताय। मध्वः। रसं। सधऽमादे। याः। ते।
धाराः। मधुऽश्चुतः। अस्रग्रं। इंदो इति। ऊतये। ताभिः। पवित्रं। आ। असदः। सः। अर्ष। इंद्राय। पीत ७

© Dharmartha Trust J&K. Digitized by eGangotri

यो॥तिरः॥रोमाणि॥अव्यया॥सीदन्॥योना॥वनेषु॥आ॥त्वा॥इंदो॥इति॥परि॥स्रव॥स्वादिष्ठः॥अंगिरःऽभ्यः
॥वरिवःऽवित्॥घृतं॥पयः॥अयं॥विऽचर्षणिः॥पवमानः॥सः॥चेतति॥हिन्वानः॥आप्यं॥बृहत्॥२५
॥एषः॥वृषा॥वृषऽव्रतः॥पवमानः॥अशस्तिऽहा॥करत्॥वसूनि॥दाशुषे॥आ॥पवस्व॥सहस्रिणं॥र
यिं॥गोऽमंतं॥अश्विनं॥पुरुऽचंद्रं॥पुरुऽस्पृहं॥एषः॥स्यः॥परि॥सिच्यते॥मर्मृज्यमानः॥आयुऽभिः॥उरुऽ
गायः॥कविऽक्रतुः॥सहस्रऽऊतिः॥शतऽमघः॥विऽमानः॥रजसः॥कविः॥इंद्राय॥पवते॥मदः॥गिरा॥जा
तः॥इह॥स्तुतः॥इंदुः॥इंद्राय॥धीयते॥विः॥योना॥वसतौऽइव॥२६॥पवमानः॥सुतः॥नृऽभिः॥सोमः॥
वाजंऽइव॥असरत्॥चमूषु॥शक्मना॥आऽसदं॥तं॥त्रिऽपृष्ठे॥त्रिऽवंधुरे॥रथे॥युंजंति॥यातवे॥ऋषी

© Dharmartha Trust J&K. Digitized by eGangotri

प. स. णां। सप्त। धीतिऽभिः। तं। सोतारः। धनःऽस्पृतं। आशुं। वाजाय। यातवे। हरिं। हिनोत। वाजिनं। आ।
८ विशन्। कलशं। सुतः। विश्वाः। अर्षन्। अभि। श्रियः। शूरः। न। गोषु। तिष्ठति। आ। ते। इंदोइति।
मदाय। कं। पयः। दुहंति। आयवः। देवाः। देवेभ्यः। मधु॥ २०॥ आ। नः। सोमं। पवित्रे। आ। सृजत।
मधुमत्ऽतमं। देवेभ्यः। देवश्रुत्ऽतमं। एते। सोमाः। असृक्षत। गृणानाः। श्रवसे। महे। मदि
न्ऽतमस्य। धारया। अभि। गव्यानि। वीतये। नृम्णा। पुनानः। अर्षसि। सनत्ऽवाजः। परि।
स्रव। उत। नः। गोऽमतीः। इषः। विश्वाः। अर्ष। परिऽस्तुभः। गृणानः। जमत्ऽअग्निना। पवस्व।
वाचः। अग्रियः। सोम। चित्राभिः। ऊतिऽभिः। अभि। विश्वानि। काव्या॥ २१॥ त्वां। समुद्रियाः। ८

© Dharmartha Trust J&K. Digitized by eGangotri

अपः। अग्रियः। वाचः। ईरयन्। पवस्व। विश्वंऽएजय। तुभ्य। इमा। भुवना। कवे। महिम्ने। सोम। तस्थिरे। तु
भ्यं। अर्षंति। सिंधवः। प्र। ते। दिवः। न। वृष्टयः। धाराः। यंति। असश्चतः। अभि। शुक्रां। उपऽस्तिरं। इंद्राय।
इंदुं। पुनीतन। उग्रं। दक्षाय। साधनं। ईशानं। वीतिऽराधसं। पवमानः। ऋतः। कविः। सोमः। पवित्रं।
आ। असदत्। दधत्। स्तोत्रे। सुऽवीर्यं॥३०॥ आ। पवस्व। सहस्रिणं। रयिं। सोम। सुऽवीर्यं। अस्मे इ
ति। श्रवांसि। धारय। इषं। ऊर्जं। च। पिन्वसे। इंद्राय। मत्सरिन्ऽतमः। चमूषु। आ। नि। सीदसि। सु
तः। इंद्राय। [illegible]विष्णवे। सोमः। कलशे। अक्षरत्। मधुऽमान्। अस्तु। वायवे। एते। असृग्रं।
आशवः। अति। ह्वरांसि। बभ्रवः। सोमाः। ऋतस्य। धारया। इंद्रं। वर्धंतः। अपःऽतुरः। कृण्वंतः। विश्वं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ आर्यौ। अपऽघ्नंतः। अराव्णः॥ ३॥ सुताः। अनु। स्वं। आ। रजः। अभि। अर्षंति। बभ्रवः। इंद्रं। गछंतः। इं
९ दवः। अया। पवस्व। धारया। यया। सूर्यं। अरोचयः। हिन्वानः। मानुषीः। [illegible] अपः। अयुक्त।
9 सूरः। एतशं। पवमानः। मनौ। अधि। अंतरिक्षेण। यातवे। उत। त्याः। हरितः। दश। सूरः। अयुक्त।
यातवे। इंदुः। इंद्रः। इति। ब्रुवन्। परि। इतः। वायवे। सुतं। गिरः। इंद्राय। मत्सरं। अव्यः। वारेषु। सिं
चत॥ ३॥ पवमान। विदाः। रयिं। अस्मभ्यं। सोम। [illegible] दुस्तरं। यः। दुःऽनशः। वनुष्यता।
अभि। अर्ष। सहस्रिणं। रयिं। गोऽमंतं। अश्विनं। अभि। वाजं। उत। श्रवः। सोमः। देवः। न। सूर्यः।
अद्रिऽभिः। पवते। सुतः। दधानः। कलशे। रसं। एते। धामानि। आर्या। शुक्राः। ऋतस्य। धार ९

© Dharmartha Trust J&K. Digitized by eGangotri

या। वाजं। गोऽमंतं। असुरन्। सुताः। इंद्राय। वज्रिणे। सोमासः। दधिऽआशिरः। पवित्रं। अति। असृर
न्। १। यात्रा। सोमम्। मधुमत्ऽतमः। राया। अर्ष। पवित्रे। आ। मदः। यः। देवऽवीतमः। तं। ईं। मिति। मृजंति
। आयवः। हरिं। नदीषु। वाजिनं। इंदुं। इंद्राय। मत्सरं। आ। पवस्व। हिरण्यऽवत्। अश्वऽवत्। सोम। वी
रऽवत्। वाजं। गोऽमंतं। आ। भर। परि। वाजे। न। वाजऽयुं। अव्यः। वारेषु। सिंचत। इंद्राय। मधुमत्ऽ
तमं। कविं। मृजंति। मर्ज्यं। धीभिः। विप्राः। अवस्यवः। वृषा। कनिक्रत्। अर्षति॥ ३॥ वृषणं। धी
भिः। अप्ऽतुरं। सोमं। ऋतस्य। धारया। मती। विप्राः। सं। अस्वरन्। पवस्व। देव। आयुषक्। इंद्रं।
गच्छतु। ते। मदः। वायुं। आ। रोह। धर्मणा। पवमान। नि। तोशसे। रयिं। सोम। श्रवाय्यं। प्रियः। स

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ मुद्रं। आ। विश। अप॒ऽघ्नन्। पव॒स्व॒। सो॒म॒। धर्मऽकृतुऽवित्। सो॒म॒। म॒त्स॒रः। नु॒द॒स्व॒। अदेवऽयुं। जनं।
१० पव॒मा॒नाः। अ॒सृ॒क्ष॒त॒। सोमाः। शु॒क्रासः। इंदवः। अ॒भि। विश्वा॑नि। काव्या॑॥ ३४॥ पव॒मा॒ना॒
सः। आ॒शवः। शु॒भ्राः। अ॒सृ॒ग्रं॒। इंदवः। घ्नंतः। विश्वाः। अप॑। द्विषः। पव॒मा॒नाः। दि॒वः। परि॑। अंत
रिक्षात्। अ॒सृ॒क्ष॒त॒। पृ॒थि॒व्याः। अधि॑। सानविं। पु॒ना॒नः। सोमा॒। धारया। इं॒दुः। इति॑। विश्वाः। अ
पा। स्त्रिधः। अ॒हि। रक्षां॑सि। सुऽक्रतो इति॑ सुऽक्रतो। अ॒प॒ऽघ्नन्। सो॒म॒। र॒क्षसः। अ॒भि। अ॒र्षा॒। क
निक्रदत्। द्यु॒ऽमंतं। शुष्मं। [illegible]। उ॒त्ऽत॒मं। अ॒स्मे इति॑। व॒स्व॒नि। धा॒र॒या॒। सो॒म॒। दि॒व्या
नि। पार्थिवा। इं॒दो॒ इति॑। विश्वा॑नि। वार्या॑॥ ३५॥ वृषा। सो॒म॒। द्यु॒ऽमान्। अ॒सि॒। वृषा। दे॒व॒। वृष॒ऽ

© Dharmartha Trust J&K. Digitized by eGangotri

व्रतः। वृषा। धर्माणि। दधिषे। वृष्णः। ते। वृष्ण्यं। शवः। वृषा। वनं। वृषा। मदः। सत्यं। वृषन्। वृषा। इत्।
असि। अश्वः। न। चक्रदः। वृषा। सं। गाः। इंदो इति। सं। अर्वतः। वि। नः। राये। दुरः। वृधि। असृक्षत।
प्र। वाजिनः। गव्या। सोमासः। अश्वऽया। शुक्रासः। वीरऽया। आशवः। शुंभमानाः। ऋतयुऽभिः। मृ
ज्यमानाः। गभस्त्योः। पवंते। वारे। अव्यये॥३५॥ ते। विश्वा। दाशुषे। वसु। सोमाः। दिव्यानि। पार्थि
वा। पवंतां। आ। अंतरिक्ष्या। पवमानस्य। विश्वऽवित्। प्र। ते। सर्गाः। असृक्षत। सूर्यस्यऽइव। न। र
श्मयः। केतुं। कृण्वन्। दिवः। परि। विश्वा। रूपा। अभि। अर्षसि। समुद्रः। सोम। पिन्वसे। हिन्वानः। वा
चं। इष्यसि। पवमान। विऽधर्मणि। अक्रान्। देवः। न। सूर्यः। इंदुः। पविष्ट। चेतनः। प्रियः। कवीनां। म

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ ती।सृजत्।अभ्रं।रथीःऽइव॥ २७॥ऊर्मिः।यः।ते।पवित्रे।आ।देवऽअवीः।परिऽअक्षरत्।सीदन्।
११ ऋतस्य।योनिं।आ।सः।नः।अर्ष।पवित्रे।आ।मदः।यः।देवऽवीतमः।इंदो इति।इंद्राय।पीतये।
इषे।पवस्व।धारया।मृज्यमानः।मनीषिऽभिः।इंदो इति।रुचा।अभि।गाः।इहि॥ पुनानः।वरि
वः।कृधि।ऊर्जं।जनाय।गिर्वणः।हरे।सृजानः।आऽशिरं।पुनानः।देवऽवीतये।इंद्रस्य।या
हि।निःऽकृतं।द्युतानः।वाजिऽभिः।यतः॥ २८॥प्र।हिन्वानासः।इंदवः।अच्छ।समुद्रं।आशवः।
धिया।जूताः।असृक्षत।मर्मृजानासः।आयवः।रथाः।समुद्रं।इंदवः।अग्मन्।ऋतस्य।यो
निं।आ।परि।नः।याहि।अस्मऽयुः।विश्वा।वसूनि।ओजसा।पाहि।नः।शर्म।वीरऽवत्।मिमा ११

© Dharmartha Trust J&K. Digitized by eGangotri

ति। वक्षि। एतशः। पदं। युजानः। ऋक्वऽभिः। ग्रा। यत्। समुद्रः। आऽहितः। आ। यत्। योनिं। हिरण्य
यं। आशुः। ऋतस्य। सीदति। जहाति। अप्रऽचेतसः। ३१। अभि। वेनाः। अनूषत। इयक्षंति। प्रऽ
चेतसः। मज्जंति। अविऽचेतसः। इंद्राय। इंदो इति। मरुत्वते। पवस्व। मधुमत्ऽतमः। ऋतस्य।
योनिं। आऽसदं। तं। त्वा। विप्राः। वचःऽविदः। परि। कृण्वंति। वेधसः। सं। त्वा। मृजंति। आयवः।
रसं। ते। मित्रः। अर्यमा। पिबंति। वरुणः। कवे। पवमानस्य। मरुतः। त्वं। सोम। विपःऽचितं।
पुनानः। वाचं। इष्यसि। इंदो इति। सहस्रऽभर्णसं।।५०।। उत। नो इति। सहस्रऽभर्णसं। वाचं।
सोम। मखस्युवं। पुनानः। इंदो इति। आ। भर। पुनानः। इंदो इति। एषां। पुरुऽहूत। जनानां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ त्रियः। समुद्रः। आ। विशा। दविद्युतत्सा। रुचा। परिऽस्तोभंत्या। रूपा। सोमाः। शुक्राः। गोऽआशिरः।
३२ हिन्वानः। हेतृऽभिः। यतः। आ। वाजं। वाजी। अक्रमीत्। सीदंतः। वनुषः। यथा। ऋधक्। सोम। स्वस्त
ये। सं। जग्मानः। दिवः। कविः। पवस्व। सूर्यः। दृशे॥ ४३॥ इति सप्तमाष्टके प्रथमोध्यायः॥ ॥
ॐ म॥ हिन्वंति भृगुर्वारुणिर्जमदग्निर्वा पवस्व शतं वैखानसा अष्टादश्यनुष्टुप् परास्तिस्र आ
ग्नेय्यं स्व सोमासि द्वात्रिंशद्भरद्वाजः कश्यपो गोतमो त्रिर्विश्वामित्रो जमदग्निर्वसिष्ठ इती
हस्तृचाः सप्तऋषयः शेषे पवित्रो वसिष्ठो वो भौवा पवस्व सोमतिस्रो नित्यद्विपदा गायत्र्यो
वितानः स्त्रिस्त्रः पौष्ण्यो वा यत्ते पवित्रं पंचाग्नेय्यः सावित्र्यग्निसावित्री वैश्वदेवी वा सामंत्या ३२

© Dharmartha Trust J&K. Digitized by eGangotri

त्रिंशीपुरउष्णिक्सांविंशानुष्टुबंत्येचतेपावमान्यध्येतरस्तुतीजागतमूर्ध्वंप्रागुशानसःप्रदेवंदश
वत्सप्रिर्भालंदनस्त्रिष्टुबंतेहेषुर्नहिरण्यस्तूपांयेत्रिष्टुभौत्रिरस्मैरेणुरादाक्षिणानवर्चंऋषभ
स्तौवैश्वामित्रोहरिंहरिमंतस्त्वक्षेपवित्रःशिशुर्नकक्षीवांस्त्रिष्टुबष्टम्यामित्रियाणिपंचकविः
हरिःऽॐमा।हिन्वंति।स्तरं।उस्रयः।स्वसारः।जामयः।पतिं।महां।इंदुं।महीयुवः।पवमाना।ऋचा।
ऋचा।देवः।देवेभ्यः।परि।विश्वा।वसूनि।आ।विश।आ।पवमाना।सुऽस्तुतिं।रश्मिं।देवेभ्यः।परि
दुवः।इषे।पवस्व।संऽयतं।रथा।हि।असि।भानुना।द्युऽमंतं।त्वा।हवामहे।पवमाना।सुऽआध्यः
आ।पवस्व।सुऽवीर्यं।मंदमानः।सुऽआयुध।इहो इति।सु।इंदो इति।आ।गहि।।३।।यत।अत्रऽभिः

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. परिऽसिच्यसे।मृज्यमानः।गभस्त्योः।द्रुणा।सधऽस्थं।अभ्रुषे।त्रा।सोमा।या।व्युभ्वऽवत्र।
३२ पवमानाय।गायत।महे।सहस्रऽचक्षसे।यस्य।वर्णं।मधुऽश्चुतं।हरिं।[illegible]।हिन्वं
13 ति।अद्रिऽभिः।इंदुं।इंद्राय।पीतये।नस्य।ते।वाजिनः।वयं।विश्वा।धनानि।जिग्युषः।स
खिऽत्वं।आ।वृणीमहे।वृषा।पवस्व।धारया।मरुत्वते।च।मत्सरः।विश्वा।दधानः।ओज
सा।।रा।तं।त्वा।धर्त्तारं।ओण्योः।पवमान।स्वःऽदृशं।हिन्वे।वाजेषु।वाजिनं।अया।चित्तः।
विपा।अनेया।हरिः।पवस्व।धारया।युजं।वाजेषु।चोदय।आ।नः।इंदो।इति।महीं।इ
षं।पवस्व।विश्वऽदर्शतः।अस्मभ्यं।सोम।गातुऽवित्।आ।कऽरणः।अनूषत।इंदो।इति। ३२

© Dharmartha Trust J&K. Digitized by eGangotri

धाराभिः। ओजसा। आ। इंद्र। इंद्रस्य। पीतये। विशायस्य। तोमदो। रसं। तीव्रं। दुहंति। अद्रिभिः। स्तः। प

वस्व। अभिमातिऽहा। आ। राजा। मेधाभिः। ईयते। पवमानः। मनौ। अधि। अंतरिक्षेण। यातवे।

आ। नः। इंदो इति। शतऽग्विनं। गवां। पोषं। सुऽअश्व्यं। वह। भगत्तिं। ऊतये। आ। नः। सोम। सहः।

जुवः। रूपं। न। वर्चसे। भर। सुस्वानः। देवऽवीतये। अर्ष। सोम। द्युमत्। तमः। अभि। द्रोणानि। रोरु

वत्। सीदन्। श्येनः। न। योनिं। आ। अप्साः। इंद्राय। वायवे। वरुणाय। मरुत्ऽभ्यः। सोमः। अर्षति।

विष्णवे॥ ७ आ। इषं। तोकाय। नः। दधत्। अस्मभ्यं। सोम। विश्वतः। आ। पवस्व। सहस्रिणं। ॥ ये।

वा। अदः। शर्यणाऽवति। ये। आर्जीकेषु। कृत्वऽसु। ये। मध्ये। पस्त्यानां। ये। वा। जनेषु। पंचऽसु।

ये सोमासः परावति
ये अर्वावति सुन्विरे।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. नः। वृष्टिं। दिवः। परि। पवंतां। आ। सुऽवीर्यं। सुवानाः। देवासः। इंदवः। पवंते। हर्यतः। हरिः। गृ
३४ णानः। जमदग्निना। हिन्वानः। गोः। अधि। त्वचि। पाः। प्रा। शुक्रासः। वयःऽजुवः। हिन्वाना
सः। नाः। सप्तयः। श्रीणानाः। अप्ऽसु। मृंजत। तं। त्वा। सुतेषु। आऽभुवः। हिन्विरे। देवऽतातये।
14 सः। पवस्व। अनया। रुचा। आ। तं। दक्षं। मयःऽभुवं। वह्निं। अद्य। वृणीमहे। पांतं। आ। पुरुऽ
स्पृहं। आ। मंद्रं। आ। वरेण्यं। आ। विप्रं। आ। मनीषिणं।०आ। रयिं। आ। सुऽचेतुनं। आ। सु
क्रतो इति सुऽक्रतो। तनूषु। आ।०।८। पवस्व। विश्वऽचर्षणे। अभि। विश्वानि। काव्या।
सखा। सखिऽभ्यः। ईड्यः। ताभ्यां। विश्वस्य। राजसि। ये इति। पवमान। धामनी इति। प्रती ३४

© Dharmartha Trust J&K. Digitized by eGangotri

चीऽइति। सोम। तस्थुः। परि। धामानि। यानि। ता। त्वं। सोम। असि। विश्वतः। पवमान। ऋतुऽभिः। क
वे। पवस्व। जनयन्। इषः। अभि। विश्वानि। काव्या। सखा। सखिऽभ्यः। ऊतये। तव। शुक्रासः। अर्चयः
। दिवः। पृष्ठे। वि। तन्वते। पवित्रं। सोम। धामऽभिः।। ७।। तव। इमे। सप्त। सिंधवः। प्रऽशिषं। सोम।
सिस्रते। तुभ्यं। धावंति। धेनवः। प्र। सोम। याहि। धारया। सुतः। इंद्राय। मत्सरः। दधानः। अक्षि
ति। श्रवः। सं। ऊंऽइति। त्वा। धीभिः। अस्वरन्। हिन्वतीः। सप्त। जामयः। विप्रं। आजा। विवस्व
तः। मृजंति। त्वा। सं। अग्रुवः। अव्ये। जीरौ। अधि। स्वनि। रेभः। यत्। अज्यसे। वने। पवमान
स्य। ते। कवे। वाजिन्। सर्गाः। असृक्षत। अर्वंतः। न। श्रवस्यवः।। ८।। अच्छ। कोशं। मधुऽश्चुतं।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ अस्रग्नं। वारे। अव्यये। अयाव शंत। धीतयः। अछ। समुद्रं। इंदवः। अस्तं। गावः। नाधेनवः। अग्म
३५ न्। ऋतस्य। योनिं। आ। प्रा। नः। इंदो इति। महे। [illegible]पे। आपः। अर्षति। सिंधवः। यत्। गोभिः। वासयि
15 ष्यसे। अस्या। तो। सख्ये। वयां। इद्यक्षंतः। वाऽऽ। फुलयः। इंदो इति। सखिऽत्वं। उश्मसि। आ। पवस्व।
गोऽइष्ये। महे। सोम। नृऽचक्षसे। आ। इंद्रस्य। जठरे। विश। ऽऽ। महान्। असि। सोम। ज्येष्ठः। उग्रा
णां। इंदो इति। ओजिष्ठः। युध्वा। सन्। शश्वत्। जिगेथा। यः। उग्रेभ्यः। चित्। ओजीयान्। शूरेभ्यः
चित्। शूरऽतरः। भूरिऽदाभ्यः। चित्। मंहीयान्। त्वां। सोम। सूरः। आ। इषः। तोकस्य। साता। तनू
नां। वृणीमहे। सख्यायां। [illegible]। वृणीमहे। युज्याय। अग्ने। आयूंषि। पवसे। आ। सुव। ३५

© Dharmartha Trust J&K. Digitized by eGangotri

ऊर्जं। इषं। नः। च। आरे। बाधस्व। दुछुनां। अग्निः। ऋषिः। पवमानः। पांचऽजन्यः। पुरःऽहितः। तं। ईमहे। म
हाऽगयं। अग्ने। पवस्व। सुऽअपाः। अस्मे इति। वर्चः। सुऽवीर्यं। दधत्। रयिं। मयि। पोषं। पवमानः। अ
ति। स्रिधः। अभि। अर्षति। सुऽस्तुतिं। सूरः। न। विश्वऽदर्शतः। सः। मर्मृजानः। आयुऽभिः। प्रयस्वान्। प्र
यसे। हितः। इंदुः। अत्यः। विऽचक्षणः। पवमानः। ऋतं। बृहत्। शुक्रं। ज्योतिः। अजीजनत्। कृष्णा। तमां
सि। जंघनत्। पवमानस्य। जंघ्नतः। हरेः। चंद्राः। असृक्षत। जीराः। अजिरऽशोचिषः। २२। पवमानः।
रथिऽतमः। शुभ्रेभिः। शुभ्रशःऽतमः। हरिऽचंद्रः। मरुत्ऽगणः। पवमानः। वि। अश्नवत्। रश्मिऽभिः। वा
जऽसातमः। दधत्। स्तोत्रे। सुऽवीर्यं। प्र। सुवानः। इंदुः। अक्षारिति। पवित्रं। अति। अव्ययं। पुनानः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ इंदुः।इंद्रं।आ।एषः।सोमः।अधि।त्वचि।गवां।क्रीळति।अद्रिऽभिः।इंद्रं।मदाय।जोहुवत्।यस्य।ते।
३६ द्युम्नऽवत्तमा।पयः।पवमान।आऽभृतं।दिवः।तेन।नः।मृळ।जीवसे।।३।।त्वं।सोम।असि।धारयुः।
मंद्रः।ओजिष्ठः।अध्वरे।पवस्व।मंहयत्ऽरयिः।त्वं।सुतः।नृऽमादनः।दधन्वान्।मत्सरिन्ऽतमः।
16 इंद्राय।सूरिः।अंधसा।त्वं।सुस्वानः।अद्रिऽभिः।अभि।अर्ष।कनिक्रदत्।द्युऽमंतं।शुष्मं।उत्ऽत
तमं।इंदुः।हिन्वानः।अर्षति।तिरः।वाराणि।अव्यया।हरिः।वाजं।अचिक्रदत्।इंदोऽइति।वि।अ
व्ये।अर्षसि।वि।श्रवांसि।वि।सौभगा।वि।वाजान्।सोम।गोऽमतः।।४।।आ।नः।इंदोऽइति।
शतऽग्विनं।रयिं।गोऽमंतं।अश्विनं।भर।सोम।सहस्रिणं।पवमानासः।इंदवः।तिरः।पवि १६

© Dharmartha Trust J&K. Digitized by eGangotri

वे। आशवः। इंद्रं। यामेभिः। आशत। ककुहः। सोम्यः। रसः। इंदुः। इंद्राय। पूर्व्यः। आयुः। पवते। आयवे। हि
न्वंति। सूरं। उस्रयः। पवमानं। मधुऽश्चुतं। अभि। गिरा। सं। अस्वरन्। आविता। नः। अजऽअश्वः। पूषा
यामनिऽयामनि। आ। भक्षत्। कन्यासु। नः॥१४॥ अयं। सोमः। कपर्दिने। घृतं। न। पवते। मधु॥०॥ अयं।
ते। आघृणे। सुतः। घृतं। न। पवते। शुचि॥०॥ वाचः। जंतुः। कवीनां। पवस्व। सोम। धारया। देवेषु। रत्नऽधाः
असि। आ। कलशेषु। धावति। श्येनः। वर्म। वि। गाहते। अभि। द्रोणा। कनिक्रदत्। परि। प्र। सोम। ते। र
सः। असर्जि। कलशे। सुतः। श्येनः। न। तक्तः। अर्षति॥१५॥ पवस्व। सोम। मंदयन्। इंद्राय। मधुमत्ऽ
तमः। असृग्रन्। देवऽवीतये। वाजऽयंतः। रथाःऽइव। ते। सुतासः। मदिन्ऽतमाः। शुक्राः। वायुं। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. रक्षसतु । ग्रावाणः । तुन्नः । अभिऽस्तुतः । पवित्रं । सोम । गच्छसि । दधत् । स्तोत्रे । सुऽवीर्यं । एषः । तुन्नः ।
३० अभिऽस्तुतः । पवित्रं । अति । गाहते । रक्षःऽहा । वारं । अव्ययं ॥ २ ॥ यत् । अंति । यत् । च । दूरके । भयं । विं-
दति । मां । इह । पवमान । वि । तत् । जहि । पवमानः । सः । अद्य । नः । पवित्रेण । [illegible] । विऽचर्ष-
णिः । यः । पोता । सः । पुनातु । नः । यत् । ते । पवित्रं । अर्चिषि । अग्ने । विऽततं । अंतः । आ । ब्रह्म । तेन ।
पुनीहि । नः । यत् । ते । पवित्रं । अर्चिऽवत् । अग्ने । तेन । पुनीहि । नः । ब्रह्मऽसवैः । पुनीहि । नः । उभाभ्यां ।
देव । सवितः । इति । पवित्रेण । सवेन । च । मां । पुनीहि । विश्वतः ॥ ३० ॥ त्रिऽभिः । त्वं । देव । सवितः ।
वर्षिष्ठैः । सोम । धामऽभिः । अग्ने । दक्षैः । पुनीहि । नः । पुनंतु । मां । देवऽजनाः । पुनंतु । वसवः । धि- १८

17

© Dharmartha Trust J&K. Digitized by eGangotri

या। विश्वे। देवाः। पुनीत। मा। जातऽवेदः। पुनीहि। मा। प्र। प्यायस्व। प्र। स्यंदस्व। सोम। विश्वेभिः। अंशुऽ

भिः। देवेभ्यः। उत्ऽतमं। हविः। उप। प्रियं। पनिप्नतं। युवानं। आहुतिऽवृधं। अगन्म। बिभ्रतः। नमः। अ

लाय्यस्य। परशुः। ननाश। तं। आ। पवस्व। देव। सोम। आखुं। चित्। एव। देव। सोम। यः। पावमानीः

अधिऽएति। ऋषिऽभिः। संऽभृतं। रसं। सर्वं। सः। पूतं। अश्नाति। स्वदितं। मातरिश्वना। पावमानीः।

यः। अधिऽएति। ऋषिऽभिः। संऽभृतं। रसं। तस्मै। सरस्वती। दुहे। क्षीरं। सर्पिः। मधु। उदकं। ३८॥

प्र। देवं। अच्छ। मधुऽमंतः। इंदवः। असिस्यदंत। गावः। आ। न। धेनवः। बर्हिऽसदः। वचनाऽवंतः। ऊधऽ

भिः। परिऽस्रुतं। उस्रियाः। निःऽनिजं। धिरे। सः। रोरुवत्। अभि। पूर्वाः। अचिक्रदत्। उपऽआरुहः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ अथयन्।स्वादते।हरिः।तिरः।पवित्रं।परिऽयन्।उरु।ज्रयः।नि।शर्याणि।दधते।देवः।आ।वरं।वि
३८ यः।ममे।यम्या।संयती इति संऽयती।मदः।साकंऽवृधा।पयसा।पिन्वत्।अक्षिता।मही इति।अ
पारे इति।रजसी इति।विऽवेविदत्।अभिऽव्रजन्।अक्षितं।पाजः।आ।ददे।सं।मातरा।विऽचरन्
वाजयन्।अपः।प्र।मेधिरः।स्वधया।पिन्वते।पदं।अंशुः।यवेन।पिपिशे।यतः।नृऽभिः।सं।जामिऽ
भिः।नसते।रक्षते।शिरः।सं।दक्षेण।मनसा।जायते।कविः।ऋतस्य।गर्भः।निऽहितः।यमा।प
रः।यूना।ह।संता।प्रथमं।विजज्ञतुः।गुहा।हितं।जनिम।नेमं।उत्ऽयतं॥३॥मंद्रस्य।रूपं।विवि
दुः।मनीषिणः।श्येनः।यत्।अंधः।अभरत्।पराऽवतः।तं।मर्जयंत।सुऽवृधं।नदीषु।आ।उशंतं। ३८

© Dharmartha Trust J&K. Digitized by eGangotri

अंभुं।परिऽयंतं।ऋग्मियं।त्वां।मृजंति।दश।योषणः।सुतं।सोम।ऋषिऽभिः।मतिऽभिः।धीतिऽभिः।
हितं।अव्यः।वारेभिः।उत।देवहूतिऽभिः।नृऽभिः।यतः।वाजं।आ।दर्षि।सातये।परिऽप्रयंतं।वय्यं।
सुऽसंसदं।सोमं।मनीषाः।अभि।अनूषत।स्तुभः।यः।धारया।मधुऽमान्।ऊर्मिणा।दिवः।इयर्ति।वाचं।र
यिषाट्।अमर्त्यः।अयं।दिवः।इयर्ति।विश्वं।आ।रजः।सोमः।पुनानः।कलशेषु।सीदति।अत्रऽभिः।गो
भिः।मृज्यते।अद्रिऽभिः।सुतः।पुनानः।इंदुः।वरिवः।विदत्।प्रियं।एव।नः।सोम।परिऽसिच्यमानः।वयः।
दधत्।चित्रऽतमं।पवस्व।अद्वेषे इति।द्यावापृथिवी इति।हुवेम।देवाः।धत्त।रयिं।अस्मे इति।सुऽवी
रं।२०।इषुः।न।धन्वन्।प्रति।धीयते।मतिः।वत्सः।मातुः।उप।सर्जि।ऊधनि।उरुधाराऽइव।दुहे।

ना।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. अग्रे। आऽयती। अस्य। व्रतेषु। अवि। सोमः। इष्यते। उपो इति। मतिः। पृच्यते। सिच्यते। मधु। मंद्रऽअ
३९ जनी। चोदते। अंतः। आसनि। पवमानः। संऽतनिः। प्रघ्नतांऽइव। मधुऽमान्। द्रप्सः। परि। वारं। अर्ष
ति। अव्ये। वधूऽयुः। पवते। परि। त्वचि। श्रथ्नीते। नप्तीः। अदितेः। ऋतं। यते। हरिः। अक्रान्। यजतः।
संऽयतः। मदः। नृम्णा। शिशानः। महिषः। न। शोभते। उक्षा। मिमाति। प्रति। यंति। धेनवः। देवस्य। दे
वीः। उप। यंति। निःऽकृतं। अति। अक्रमीत्। अर्जुनं। वारं। अव्ययं। अत्कं। न। निक्तं। परि। सोमः। अ
व्यत। अमृक्तेन। रुशता। वाससा। हरिः। अमर्त्यः। निःऽनिजानः। परि। व्यत। दिवः। पृष्ठं। बर्हणा।
निःऽनिजे। कृत। उपऽस्तरणं। चम्वोः। नभस्मयं॥ २३॥ सूर्यस्यऽइव। रश्मयः। द्रावयित्नवः। मत्स ३९

© Dharmartha Trust J&K. Digitized by eGangotri

रा। स्वः। प्र ऽस्तुपः। साकं। ईरते। तंतुं। ततं। परि। सर्गासः। आशवः। न। इंद्रात्। ऋते। पवते। धाम। किं।

चन। सिंधोःऽइव। प्रवणे। निम्ने। आशवः। वृषऽच्युताः। मदासः। गातुं। आशत। शं। नः। निऽवेशे।

द्विऽपदे। चतुःऽपदे। अस्मे इति। वाजाः। सोम। तिष्ठंतु। कृष्टयः। आ। नः। पवस्व। वसुऽमत्। हिरण्य

ऽवत्। अश्वऽवत्। गोऽमत्। यवऽमत्। सुऽवीर्यं। यूयं। हि। सोम। पितरः। मम। स्थन। दिवः। मूर्ध्ना

नः। प्रऽस्थिताः। वयःऽकृतः। एते। सोमाः। पवमानासः। इंद्रं। रथाःऽइव। प्र। अयासुः। सातिं। अच्छ। सु

ताः। पवित्रं। अति। यंति। अव्यं। हित्वी। वव्रिं। हरितः। वृष्टिं। अच्छ। इंदो इति। इंद्राय। बृहते। पवस्व।

सुऽमृळीकः। अनवद्यः। रिशादाः। भर। चंद्राणि। गृणते। वसूनि। गौं। ररा। त्रिः। अस्मै। सप्ताधे

दैवै द्यावापृथिवीप्रावतंनः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ नः। दुदुक्षे। सत्यां। आऽशिरं। पूर्व्यं। विऽओमनि। चत्वारि। अन्या। भुवनानि। निःऽनिजे। चारूणि। चक्रे।
२० यत्। ऋतैः। अवर्धत। सः। भिक्षमाणः। अमृतस्य। चारुणः। उभे इति। द्यावा। काव्येन। वि। शश्रथे।
तेजिष्ठाः। अपः। मंहना। परि। व्यत। यदि। देवस्य। श्रवसा। सदः। विदुः। ते। अस्य। संतु। केतवः। अमृ-
त्यवः। अदाभ्यासः। जनुषी इति। उभे इति। अनु। येभिः। नृम्णा। च। देव्या। च। पुनते। आत्। इत्। राजा-
नं। मननाः। अगृभ्णत। सः। मृज्यमानः। दशऽभिः। सुकर्मऽभिः। प्र। मध्यमासु। मातृषु। प्रऽमे। स-
चा। अमृतानि। पानः। अमृतस्य। चारुणः। उभे इति। नृऽचक्षाः। अनु। पश्यते। विशौ। सः। मर्मृजानः।
इंद्रियाय। धायसे। आ। उभे इति। अंतरिति। रोदसी इति। हर्षते। हितः। वृषा। शुष्मेण। बाधते। वि। दुःऽ २०

घ

© Dharmartha Trust J&K. Digitized by eGangotri

मतीः।आऽदेदिशानः।शर्यहाऽइव।शुरुधः॥२॥सः।मातरा।न।ददृशानः।उस्रियः।नानदत्।एति।मरु

तांऽइव।स्वनः।जानन्।ऋतं।प्रथमं।यत्।स्वःऽनरं।प्रऽशस्तये।कं।अवृणीत।सुऽक्रतुः।रुवति।भी

मः।वृषभः।तविष्यया।शृंगेऽइति।शिशानः।हरिणीऽइति।विऽचक्षणः।आ।योनिं।सोमः।सुऽकृतं।नि।

सीदति।गव्ययी।त्वक्।भवति।निःऽनिक्।अव्ययी।शुचिः।पुनानः।तन्वं।अरेपसं।अव्ये।हरिः।नि।

अधाविष्ट।सानवि।जुष्टः।मित्राय।वरुणाय।वायवे।त्रिऽधातु।मधु।क्रियते।सुकर्मऽभिः।पवस्व।

सोम।देवऽवीतये।वृषा।इंद्रस्य।हार्दि।सोमऽधानं।आ।विश।पुरा।नः।बाधात्।दुःऽइता।अति।

पारय।क्षेत्रऽवित्।हि।दिशः।आह।विऽपृच्छते।हितः।न।सप्तिः।अभि।वाजं।अर्ष।इंद्रस्य।इंदोइति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰सं॰ जठरे। आ। पवस्व। नाना। सिंधुः। अति। पर्षि। विद्वान्। शूरः। न। युध्यन्। अव। नः। निदः।
२१ स्पः। इति। स्पः। रक्षा। आ। दक्षिणा। सृज्यते। शुष्मी। आऽसद्यं। वेति। द्रुहः। रक्षसः। पाति। जागृविः।
हरिः। ओपशं। कृणुते। नभः। पयः। उपऽस्तिरे। चम्वोः। ब्रह्म। निःऽनिजे। प्र। स्तुभि। हाऽइव। भूषः। ए
ति। रोरुवत्। असुर्यं। वर्णं। निः। रिणीते। अस्य। तं। जहाति। वव्रिं। पितुः। एति। निःऽकृतं। उपऽप्रु
तं। कृणुते। निःऽनिजं। तना। अद्रिऽभिः। सुतः। पवते। गभस्त्योः। वृषऽयते। नभसा। वेपते। मती।
सः। मोदते। नसते। साधते। गिरा। नेनिक्ते। अप्ऽसु। यजते। परीमणि। परि। द्युक्षं। सहसः।
पर्वतऽवृधं। मध्वः। सिंचंति। हर्म्यस्य। सक्षणिं। आ। यस्मिन्। गावः। सुहुतऽअदः। ऊधनि। मूर्द्ध २१

© Dharmartha Trust J&K. Digitized by eGangotri

न्। श्रीणंति। अग्नियं। वरीमऽभिः। स्तोऽइ। मितिर यं। न। मुरिजोः। अहेषत। दश। स्वसारः। अदितेः। उपऽ
स्थे। आ। जिगातृ। उप। ज्मयति। गोः। अपीच्यं। पदं। यत्। अस्य। मतुथाः। अजीजनन्। स्पा। श्ये
नः। न। योनिं। सदनं। धिया। कृतं। हिरण्ययं। आऽसदं। देवः। आ। ईषति। आ। ईमिति। रिणंति। ब
र्हिषि। प्रियं। गिरा। अश्वः। न। देवान्। अपि। एति। यज्ञियः। परा। विऽअक्तः। अरुषः। दिवः। कविः। रूपा।
त्रिःऽपृष्ठः। अनविऽहृ। गाः। अभि। सहस्रऽनीतिः। यतिः। पराऽयतिः। रेभः। न। पूर्वीः। उषसः। वि। राजति।
त्विषं। रूपं। कृणुते। वर्णः। अस्य। सः। यत्र। अशयत्। संऽऋता। सेधति। स्रिधः। अप्साः। याति। स्वधया।
दैव्यं। जनं। सं। सुऽस्तुती। नसते। [illegible]ते। सं। गोऽअग्रया। वृक्षाःऽइव। वृथा। परिऽयन्। अरावीत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. अधि। त्रिषीः। अधि। त्ना। सूर्यस्य। दिव्यः। सुऽपर्णः। अव। चु। सा[illegible]ला। क्षां। सोमः। परि। क्रतुना।
२२ पश्यते। जनाः। रथा। हरिं। मृजंति। अरुषः। न। युज्यते। सं। धेनुऽभिः। कलशे। सोमः। अज्यते। उत्। वां।
चं। ईरयति। हिन्वते। मती। पुरुऽस्तुतस्य। कति। चित्। परिऽप्रियः। सा। कं। वदंति। बहवः। मनीषिणः।
इंद्रस्य। सोमं। जठरे। यत्। आऽदुहुः। यदि। मृजंति। सुऽगभस्तयः। नरः। सऽनीळाभिः। दशऽभिः। का
म्यं। मधु। अरममाणः। अति। एति। गाः। अभि। सूर्यस्य। प्रियं। दुहितुः। तिरः। रवं। अनु। अस्मै। जो
षं। अभरत्। विनंऽगसः। सं। द्वयीभिः। स्वसृऽभिः। क्षेति। जामिऽभिः। नरः। धूतः। आद्रिऽसुतः। बर्हि
षि। प्रियः। पतिः। गवां। प्रऽदिवः। इंदुः। ऋत्वियः। पुरंधिऽवान्। मनुषः। यज्ञऽसाधनः। शुचिः। धिया। २२

© Dharmartha Trust J&K. Digitized by eGangotri

पवते। सोमः। इंद्र। ते। नबाहुऽभ्यां। चोदितः। धारया। सुतः। [illegible]ः। अनुऽस्वधां। पवते। सोमः। इंद्र। ते। आ।
अप्राः। क्रतून्। सं। अजैः। अध्वरे। मतीः। वेः। न। द्रुऽसत्। चम्वोः। आ। असदत्। हरिः॥२७॥ अंशुं। दुहं
ति। स्तनयंतं। अक्षितं। कविं। कवयः। अपसः। मनीषिणः। सं। ईं। इति। मतयः। यंति। संऽयतः। ऋतस्य। गा वः
योना। सदने। पुनःऽभुवः। नाभा। पृथिव्याः। धरुणः। महः। दिवः। अपां। ऊर्मौ। सिंधुषु। अंतः। उक्षितः।
इंद्रस्य। वज्रः। वृषभः। विभुऽवसुः। सोमः। हृदे। पवते। चारु। मत्सरः। सः। तु। पवस्व। परि। पार्थिवं। रजः।
स्तोत्रे। शिक्षन्। आऽधून्वते। च। सुक्रतो इति सुऽक्रतो। मा। नः। निः। भाक्। वसुनः। सदनऽस्पृशः।
रयिं। पिशंगं। बहुलं। वसीमहि। आ। तु। नः। इंद्रो इति। शतऽदातु। अश्व्यं। सहस्रऽदातु। पशुऽमत्।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ हिरण्यऽवत्।उप।मास्व।बृहतीः।रेवतीः।इषः।अधि।स्तोत्रस्य।पवमान।नः।गहि॥र।ना।स्त्रब्के।
२३ द्रप्सस्य।धमतः।सं।अस्वरन्।ऋतस्य।योना।सं।अरंत।नाभयः।त्रीन्।सः।मूर्द्धः।असुरः।चक्रे।
आऽरभे।सत्यस्य।नावः।सुऽकृतं।अपीपरन्।सम्यक्।संम्यंचः।महिषाः।अहेषत।सिंधोः।ऊ
23 र्मौ।अधि।वेनाः।अवीविपन्।मधोः।धाराभिः।जनयंतः।अर्कं।इत्।प्रियां।इंद्रस्य।तन्वं।अवीवृ
धन्।पवित्रऽवंतः।परि।वाचं।आसते।पिता।एषां।प्रत्नः।अभि।रक्षति।व्रतं।महः।समुद्रं।वरुणः।
तिरः।दधे।धीराः।इत्।शेकुः।धरुणेषु।आऽरभं।सहस्रऽधारे।अव।ते।सं।अस्वरन्।दिवः।
नाके।मधुऽजिह्वाः।असश्चतः।अस्य।स्पशः।न।नि।मिषंति।भूर्णयः।पदेऽपदे।पाशिनः।संति। २३

© Dharmartha Trust J&K. Digitized by eGangotri

ॐ॰ध्यायेसप्तरचरन्

सेतवः। पितुः। मातुः। अधि। आ। ये। सं ऽअस्वरन्। ऋचा। शोचंतः। संऽदहंतः। अव्रतान्। इंद्रऽद्विष्टां। अप।
धमंति। मायया। त्वचं। असिक्नीं। भूमनः। दिवः। परि। २०॥ प्रत्नात्। मानात्। ०॥ श्लोकऽयंत्रासः। रभ
सस्य। मंतवः। अप। अनक्षासः। बधिराः। अहासत। ऋतस्य। पंथां। न। तरंति। दुःऽकृतः। सहस्रऽधारे।
विऽतते। पवित्रे। आ। वाचं। पुनंति। कवयः। मनीषिणः। रुद्रासः। एषां। इषिराः। अद्रुहः। स्पशः। सुऽअं
चः। सुऽदृशः। नृऽचक्षसः। ऋतस्य। गोपाः। न। दभाय। सुऽक्रतुः। त्री। सः। पवित्रा। हृदि। अंतः। आ। द
धे। विद्वान्। सः। विश्वा। भुवना। अभि। पश्यति। अव। अजुष्टान्। विध्यति। कर्ते। अव्रतान्। ऋतस्य।
तंतुः। विऽततः। पवित्रे। आ। जिह्वायाः। अग्रे। वरुणस्य। मायया। धीराः। चित्। तत्। संऽइनक्षंतः। आश

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. ना।अत्र।कर्त्त।अव।पदाति।अप्सःऽसुः॥३०॥शिशुः।न।जातः।अव।चक्रदत्।वने।स्वः।यत्।वाजी।अ

२४ रुषः।सिसासति।दिवः।रेतसा।सचते।पयःऽवृधा।तं।ईमहे।सुऽमती।शर्म।सऽप्रथः।दिवः।यः।

स्कंभः।धरुणः।सुऽआततः।आऽपूर्णः।अंशुः।परिऽएति।विश्वतः।सः।इमे इति।मही इति।रोदसी इ

२५ ति।यक्षत्।आऽवृता।समीचीने इति संऽईचीने।धोदार।सं।इषः।कविः।महिः।सरः।सुऽकृतं।सोम्यं।

मधु।उर्वी।गव्यूतिः।अदितेः।ऋतं।यते।ईशे।यः।वृष्टेः।इतः।उस्रियः।वृषा।अपां।नेता।यः।इतःऽऊ

न मेः। तिः।ऋग्मियः।आत्मन्ऽवत्।दुह्यते।घृतं।पयः।ऋतस्य।नाभिः।अमृतं।वि।जायते।संऽईचीनाः।

सुऽदानवः।प्रीणंति।तं।नरः।हितं।अव।मेहंति।पेरवः।अरावीत्।अंशुः।सचमानः।ऊर्मिणा।दे २४

© Dharmartha Trust J&K. Digitized by eGangotri

वऽअव्यं।मनुषा।पिन्वति।त्वचं।दधाति।गर्भं।अदितेः।उपऽस्थे।आ।येन।तोकं।च।तनयं।च।धामहे॥३॥
सहस्रऽधारे।अव।ताः।असश्चतः।तृतीये।सं।तु।रजसि।प्रजाऽवतीः।चतस्रः।नाभः।निऽहिताः।अवः।दि
वः।हविः।भरंति।अमृतं।घृतऽश्चुतः।श्वेतं।रूपं।कृणुते।यत्।सिसासति।सोमः।मीढ्वान्।असुरः।वेद।
भूमनः।धिया।शमी।सचते।सः।ईं।अभि।प्रऽवत्।दिवः।कवंधं।अव।दर्षत्।उद्रिणं॥४॥ काष्मन्।आ।वा
जी।अक्रमीत्।ससऽवान्।आ।हिन्विरे।मनसा।देवऽयंतः।कक्षीवते।शतऽहिमाय।गोनां।आऽभिः।
सोमा।पपचानस्य।ते।रसः।अव्यः।वारं।वि।पवमान।धावति।सः।मृज्यमानः।कविऽभिः।मदिन्ऽतम।
स्वदस्व।इंद्राय।पवमान।पीतये॥५॥अभि।प्रियाणि।पवते।चनःऽहितः।नामानि।यह्वः।अधि।येषु।

© Dharmartha Trust J&K. Digitized by eGangotri

अभीमृतस्य दोहना अनूषत

यः

प.स वर्द्धते। आ। सूर्यस्य। बृहतः। बृहन्। अधि। रथं। विष्वंचं। अरुहत्। विऽचक्षणः। ऋतस्य। जिह्वा। पवते।
२५ मधु। प्रियं। वक्ता। पतिः। धियः। अस्याः। अदाभ्यः। दधाति। पुत्रः। पित्रोः। अपीच्यं। नाम। तृतीयं। अधि। रो
चने। दिवः। अव। द्युतानः। कलशान्। अचिक्रदत्। नृऽभिः। येमानः। कोशे। आ। हिरण्यये। अधि। त्रिऽ
पृष्ठः। उषसः। वि। राजति। अद्रिऽभिः। सुतः। मतिऽभिः। चनःऽहितः। प्रऽरोचयन्। रोदसी इति। मातरा। शुचिः।
रोमाणि। अव्या। समया। वि। धावति। मधोः। धारा। पिन्वमाना। दिवेऽदिवे। परि। सोम। प्र। धन्व। स्वस्तये।
नृऽभिः। पुनानः। अभि। वासय। आऽशिरं। ये। ते। मदाः। आहनसः। विऽहायसः। तेभिः। इंद्रं। चोदय। दा
तवे। मघं॥ ३३॥ इति सप्तमाष्टके द्वितीयोध्यायः॥ ॥ ७॥ ७॥ ॥ ७॥ ॥ ७॥ ७॥ २५

25

॥ओं म्॥ धर्तेयष्प्रराजाचोदस्वः सोमस्यवस्तुभीर ह्वाजः प्रसोमस्यासा॥ यैतित्रिष्टुबंतेपवित्रंतेपवि
त्रंः पवस्ववाच्यः प्रजापतिरिंद्रायहूदशवोमार्गवोद्वित्रिष्टुबंतंप्रतेष्ठाचत्वारिंशद्दक्षिणादशर्वी
अरुष्णमाषाः प्रथमेसिकतानिवावरीद्वितीयेपश्निर्योआस्तृतीयेत्रयश्वतुर्थेत्रिः पंचांत्यामत्स्सम
दः प्रतुनवोयंशनायंसोमोष्टौप्रोस्यसप्तप्रहिन्वानः षड्डुसिष्ठः॥ ॥ओं मः॥ धर्त्ता॥ दिवः॥ पवते॥ कृ
त्व्यः॥ रसः॥ दक्षः॥ देवानां॥ अनुऽमाद्यः॥ नृऽभिः॥ हरिः॥ सृजानः॥ अत्यः॥ न॥ सत्वऽभिः॥ वृथा॥ पाजांसि॥ कृ
णुते॥ नदीषु॥ आ॥ भरः॥ न॥ धन्व॥ आयुधा॥ गभस्त्योः॥ स्वः॥ इति॥ स्वः॥ सिसासन्॥ रथिरः॥ गोऽइष्टिषु॥
इंद्रस्य॥ शुष्मं॥ ईरयन्॥ अपः॥ स्युऽभिः॥ इंदुः॥ हिन्वानः॥ अज्यते॥ मनीषिऽभिः॥ इंद्रस्य॥ सोमः॥ पवमानः॥

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ ऊर्मिणा। न। विप्रमाणः। जठरेषु। आ। विश। प्र। नः। पिन्व। वि। घृत्। अभ्राःऽइव। रोदसी इति। धिया।
२५ न। वाजी। न। उप। मासि। शश्वतः। विश्वस्य। राजा। पवते। स्वःऽदृशः। ऋतस्य। धीतिं। ऋषिषाट्। अवी
वशत्। यः। सूर्यस्य। असिरेण। मृज्यते। पिता। मतीनां। असमष्टऽकाव्यः। रपाःऽइव। यूथा। परि। को
शं। अर्षसि। अपां। उपऽस्थे। वृषभः। कनिक्रदत्। सः। इंद्राय। पवसे। मत्सरिन्ऽतमः। यथा। जेषाम। सं
ऽइथे। त्वाऽऊतयः॥ ३॥ एषः। स्यः। कोशे। मधुऽमान्। अचिक्रदत्। इंद्रस्य। वज्रः। वपुषः। वपुःऽतरः। अ
३ भि। ईं। ऋतस्य। सुऽघाः। घृतऽश्चुतः। वाश्राः। अर्षंति। पयसाऽइव। धेनवः। स्वः। पूर्व्यः। पवते। यं। दिवः।
परि। श्येनः। मथायत्। इषितः। तिरः। रजः। सः। मध्वः। आ। युवते। वेविजानः। इत्। कृशानोः। अस्तुः। २५

26

© Dharmartha Trust J&K. Digitized by eGangotri

मनसा।अहा।विभ्युषा।ते।नः।पूर्व्यासः।उपसः।इंदवः।मेहा।वाजाः।या।धन्वंतु।गोऽमंतो।ईक्षेण्यासः।अह्यः।न।
चारवः।ब्रह्मऽब्रह्म।ये।जुजुषुः।हविःऽहविः।अयं।नः।विद्वान्।वनवत्।वनुष्यतः।इंदुः।सत्राचा।मनसा।पु
रुऽस्तुतः।इनस्य।यः।सदने।गर्भं।आऽदधे।गवां।उरुब्जं।अभि।अर्षति।व्रजं।चक्रिः।दिवः।पवते।कृत्व्यः।
रसः।महान्।अदब्धः।वरुणः।हुरुक्।यते।असावि।मित्रः।वृजनेषु।यज्ञियः।अत्यः।न।यूथे।वृषऽयुः।क
निक्रदत्।।२।।राजा।वाचं।जनयन्।असिस्यदत्।अपः।वसानः।अभि।गाः।इयक्षति।गृभ्णाति।
रिप्रं।अविः।अस्य।तान्वा।शुद्धः।देवानां।उप।याति।निःऽकृतं।इंद्राय।सोम।परि।सिच्यसे।नृऽभिः।नृऽ
चक्षाः।ऊर्मिः।कविः।अज्यसे।वने।पूर्वीः।हि।ते।स्रुतयः।संति।यातवे।सहस्रं।अश्वाः।हरयः।चमूऽसदः।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. समुद्रियाः। अप्सरसः। मनीषिणं। आसीनाः। अंतः। अभि। सोमं। अक्षरन्। ताः। ईं। हिन्वंति। हर्म्यस्य।
२८ सक्षणिं। या। वंते। सुम्नं। पवमानं। अक्षितं। गोऽजित्। नः। सोमः। रथऽजित्। हिरण्यऽजित्। स्वःऽजित्।
अप्ऽजित्। पवते। सहस्रऽजित्। यं। देवासः। चक्रिरे। पीतये। मदं। स्वादिष्ठं। द्रप्सं। अरुणं। मयःऽभुवं।
एतानि। सोम। पवमानः। अस्मऽयुः। सत्यानि। कृण्वन्। द्रविणानि। अर्षसि। जहि। शत्रुं। अंतिके। दू
रके। च। यः। उर्वीं। गव्यूतिं। अभयं। च। नः। कृधि। ३। अचोदसः। नः। धन्वंतु। इंदवः। प्र। सुवानासः।
बृहत्ऽदिवेषु। हरयः। वि। च। नशन्। नः। इषः। अरातयः। अर्यः। नशंत। सनिषंत। नः। धियः। प्र। नः। धन्वं
तु। इंदवः। मदऽच्युतः। धना। वा। येभिः। अर्वतः। जुनीमसि। तिरः। मर्तस्य। कस्य। चित्। परिऽह्वृतिं। वयं। २९

© Dharmartha Trust J&K. Digitized by eGangotri

धनानि। विश्वधा। भरेमहि। उत। स्वस्याः। अरात्याः। अरिः। हि। सः। उत। अन्यस्याः। अरात्याः। वृकः।

हि। सः। धन्वन्। न। तृष्णा। सं। अरीत। तान्। अभि। सोम। जहि। पवमान। दुःऽआध्यः। दिवि। ते। नाभा।

परमः। यः। आऽददे। पृथिव्याः। ते। रुरुहुः। सानवि। क्षिपः। अद्रयः। त्वा। बप्सति। गोः। अधि। त्वचि। अप्ऽ

सु। त्वा। हस्तैः। दुदुहुः। मनीषिणः। एव। ते। इंदो इति। सुऽभ्वं। सुऽपेशसं। रसं। तुंजंति। प्रथमाः। अभिऽ

श्रियः। निदंऽनिदं। पवमान। नि। तारिषः। आविः। ते। शुष्मः। भवतु। प्रियः। मदः। ८०। सोमस्य। धा

रा। पवते। नृऽचक्षसः। ऋतेन। देवान्। हवते। दिवः। परि। बृहस्पतेः। रवथेन। वि। दिद्युते। समुद्रासः।

न। सवनानि। विव्यचुः। यं। त्वा। वाजिन्। अघ्न्याः। अभि। अनूषत। अयःऽहतं। योनिं। आ। रोहसि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स धुऽमान्। मघोनां। आयुः। प्रऽतिरन्। महि। श्रवः। इंद्राय। सोम। पवसे। वृषा। मदः। आ। इंद्रस्य। कुक्षा। प
२८ वते। मदिन्ऽतमः। ऊर्जं। वसानः। श्रवसे। सुऽमंगलः। प्रत्यङ्। सः। विश्वा। भुवना। अभि। पप्रथे। क्रीळ
न्। हरिः। अत्यः। स्यंदते। वृषा। तं। त्वा। देवेभ्यः। मधुमत्ऽतमं। नरः। सहस्रऽधारं। दुहते। दश। क्षिपः। नृऽ
भिः। सोम। प्रऽच्युतः। ग्रावऽभिः। सुतः। विश्वान्। देवान्। आ। पवस्व। सहस्रऽजित्। तं। त्वा। हस्तिनः। मधुऽ
मंतं। अद्रिऽभिः। दुहंति। अप्ऽसु। वृषभं। दश। क्षिपः। इंद्रं। सोम। मादयन्। दैव्यं। जनं। सिंधोःऽइव। ऊर्मिः।
पवमानः। अर्षसि॥ ५॥ प्र। सोमस्य। पवमानस्य। ऊर्मयः। इंद्रस्य। यंति। जठरं। सुऽपेशसः। दध्ना। य ॥शिव॥
त्। ईं। उत्ऽनीताः। यशसा। गवां। दानाय। शूरं। उत्ऽअमंदिषुः। सुताः॥ अच्छ। हि। सोमः। कलशान्। असि २८

© Dharmartha Trust J&K. Digitized by eGangotri

स्यदत्। अत्यः। न। वोळ्हा। रघुऽवर्त्तनिः। वृषा। अथ। देवानां। उभयस्य। जन्मनः। विद्वान्। अश्नोति। अ
मुतः। इतः। च। यत्। आ। नः। सोम। पवमानः। किर। वसु। इंदो इति। भव। मघऽवा। राधसः। महः। शिक्ष।
वयःऽधः। वस्वः। सु। चेतुना। मा। नः। गयं। आरे। अस्मत्। परा। सिचः। आ। नः। पूषा। पवमानः। सुऽरा
तयः। मित्रः। गछंतु। वरुणः। सऽजोषसः। बृहस्पतिः। मरुतः। वायुः। अश्विना। त्वष्टा। सविता। सुऽय
मा। सरस्वती। उभे इति। द्यावापृथिवी इति। विश्वमिन्वे इति। विश्वंऽइन्वः। अर्यमा। देवः। अदितिः। विऽ
धाता। भगः। नृऽशंसः। उरु। अंतरिक्षं। विश्वे। देवाः। पवमानं। जुषंत। ८। असावि। सोमः। अरुषः।
वृषा। हरिः। राजाऽइव। दस्मः। अभि। गाः। अचिक्रदत्। पुनानः। वारं। परि। एति। अव्ययं। श्येनः। न।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. योनिं । घृतऽवंतं । आऽसदं । कविः । वेधस्या । परि । एषि । माहिनं । अत्यः । न । मृष्टः । अभि । वाजं । अर्षसि । अ
२९ पऽसेधन् । दुःऽइता । सोम । मृळय । घृतं । वसानः । परि । यासि । निःऽनिजं । पर्जन्यः । पिता । महिषस्य । पर्णि
नः । नाभा । पृथिव्याः । गिरिषु । क्षयं । दधे । स्वसारः । आपः । अभि । गाः । उत । असरन् । सं । ग्रावऽभिः । नसते ।
वीते । अध्वरे । जाया ऽइव । पत्यौ । अधि । शेवं । मंहसे । पज्रायाः । गर्भ । शृणुहि । ब्रवीमि । ते । अंतः । वाणीषु । प्र ।
चर । सु । जीवसे । अनिंद्यः । वृजने । सोम । जागृहि । यथा । पूर्वेभ्यः । शतऽसाः । अमृध्रः । सहस्रऽसाः । परि । अयाः ।
वाजं । इंदो इति । एव । पवस्व । सुविताय । नव्यसे । तव । व्रतं । अनु । आपः । सचंते ।।५।। पवित्रं । ते । विऽततं । ब्र
ह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः । अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । व २९

© Dharmartha Trust J&K. Digitized by eGangotri

हंतः। तत्। सं। आशत। तपोः। पवित्रं। विऽततं। दिवः। पदे। शोचंतः। अस्य। तंतवः। वि। अस्थिरन्। अवंति। अस्य।
पवितारं। आशवः। दिवः। पृष्ठं। अधि। तिष्ठंति। चेतसा। अरूरुचत्। उषसः। पृश्निः। अग्रियः। उक्षा। बिभ
र्ति। भुवनानि। वाजऽयुः। मायाऽविनः। ममिरे। अस्य। मायया। नृऽचक्षसः। पितरः। गर्भं। आ। दधुः।
गंधर्वः। इत्था। पदं। अस्य। रक्षति। पाति। देवानां। जनिमानि। अद्भुतः। गृभ्णाति। रिपुं। निऽधया। नि
धाऽपतिः। सुकृत्ऽतमाः। मधुनः। भक्षं। आशत। हविः। हविष्मः। महि। सद्म। दैव्यं। नभः। वसानः। परि।
यासि। अध्वरं। राजा। पवित्रऽरथः। वाजं। आ। अरुहः। सहस्रऽभृष्टिः। जयसि। श्रवः। बृहत्॥ ८॥ प
वस्व। देवऽमादनः। विऽचर्षणिः। अप्साः। इंद्राय। वरुणाय। वायवे। कृधि। नः। अद्य। वरिवः। स्वस्तिऽम

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. त्वा।उरुऽशितौ।अग्रणीः।हि।दैव्यं।जनं।आ।अयः।तस्थौ।भुवनानि।अमर्त्यः।विश्वानि।सोमः।परि।तानि।
३० अर्षति।कृण्वन्।संऽचृतं।विऽचृतं।अभिष्टये।इंदुः।सिसक्ति।उषसं।न।सूर्यः।आ।अयः।गोभिः।सृज्य
30 ते।ओषधीषु।आ।देवानां।सुम्ने।इषयन्।उप।वसुः।आ।विऽद्युता।पवते।धारया।सुतः।इंद्रं।सोमः।
मादयन्।दैव्यं।जनं।एषः।स्यः।सोमः।पवते।सहस्रऽजित्।हिन्वानः।वाचं।इषिरां।उषःऽबुधं।इंदुः।
समुद्रं।उत्।इयर्ति।वायुऽभिः।आ।इंद्रस्य।हार्दि।कलशेषु।सीदति।अभि।त्यं।गावः।पयसा।पयःऽवृ
धं।सोमं।श्रीणंति।मतिऽभिः।स्वःऽविदं।धनंऽजयः।पवते।कृत्व्यः।रसः।विप्रः।कविः।काव्येन।स्वः
ऽचनाः॥२॥इंद्राय।सोम।सुऽसुतः।परि।स्रव।अप।अमीवा।भवतु।रक्षसा।सह।मा।ते।रसस्य। ३०

© Dharmartha Trust J&K. Digitized by eGangotri

मत्सरः।द्युम्नाविनः।द्रविणस्वंतः।इहा।संतु।इंदवः।अस्मान्।सऽमर्यो।पवमान।चोदय।दक्षः।देवानां।
असि।हि।प्रियः।मदः।जहि।शत्रून्।अभि।आ।मंदनाऽयतः।पिब।इंद्र।सोमं।अव।नः।मृधः।जहि।अ
दब्धः।इंदो।इति।पवसे।मदिन्ऽतमः।आत्मा।इंद्रस्य।भवसि।धासिः।उत्ऽतमः।अभि।स्वरंति।बहवः।
मनीषिणः।राजानं।अस्य।भुवनस्य।निंसते।सहस्रऽनीथः।शतऽधारः।अद्भुतः।इंद्राय।इंदुः।पवते।
काम्यं।मधु।जयन्।क्षेत्रं।अभि।अर्ष।जयन्।अपः।उरुं।नः।गातुं।कृणु।सोम।मीढ्वः।कनिक्रदत्।कल
शे।गोभिः।अज्यसे।वि।अव्ययं।समया।वारं।अर्षसि।मर्मृज्यमानः।अत्यः।न।सानसिः।इंद्रस्य।
सोम।जठरे।सं।अक्षरः।स्वादुः।पवस्व।दिव्याय।जन्मने।स्वादुः।इंद्राय।सुहवीतुऽनाम्ने।स्वादुः।मि

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. त्रा। या। वरुणाय। वायवे। बृहस्पतये। मधुऽमान्। अदाभ्यः॥ ३॥ अस्यां। मृजंति। कलशे। दश॥ क्षिपः। प्र।
३१ विप्राणां। मतयः। वाचः। ईरते। पवमानाः। अभि। अर्षंति। सुऽस्तुतिं। आ। इंद्रं। विशंति। मदिरासः। इंदवः।
31 पवमानः। अभि। अर्ष। सुऽवीर्यं। उर्वीं। गव्यूतिं। महि। शर्म। सऽप्रथः। माकिः। नः। अस्य। परिऽसूतिः। ईश
तां। इंदो इति। जयेम। त्वया। धनंऽधनं। अधि। द्यां। अस्थात्। वृषभः। विऽचक्षणः। अरूरुचत्। वि। दि
२ सति वः। रोचना। कविः। राजा। पवित्रं। अति। एति। रोरुवत्। दिवः। पीयूषं। दुहते। नृऽचक्षसः। दिवः। नाके। मधुऽ
जिह्वाः। असश्चतः। वेनाः। दुहंति। उक्षणं। गिरिऽस्थां। अप्ऽसु। द्रप्सं। ववृधानं। समुद्रे। आ। सिंधोः।
ऊर्मा। मधुऽमंतं। पवित्रे। आ। नाके। सुऽपर्णं। उपऽपप्तिऽवांसं। गिरः। वेनानां। अकृपंत। पूर्वीः॥ रि ३३

© Dharmartha Trust J&K. Digitized by eGangotri

भुं। रिहंति। मतयः। पनिघ्नतं। हिरण्ययं। शकुनं। क्षामणिं। स्थां। ऊर्ध्वः। गंधर्वः। अधि। नाके। अस्थात्। वि
श्वा। रूपा। प्रतिऽचक्षाणः। अस्य। भानुः। शुक्रेण। शोचिषा। वि। अद्यौत्। प्र। अरूरुचत्। रोदसी इति। मा
तरा। शुचिः। २३। प्र। ते। आशवः। पवमान। धीऽजवः। मदाः। अर्षंति। रघुजाःऽइव। त्मना। दिव्याः। सुऽपर्णाः।
मधुऽमंतः। इंदवः। मदिन्ऽतमासः। परि। कोशं। आसते। प्र। ते। मदासः। मदिरासः। आशवः। असृ
क्षत। रथ्यासः। यथा। पृथक्। धेनुः। न। वत्सं। पयसा। अभि। वज्रिणं। इंद्रं। इंदवः। मधुऽमंतः। ऊर्मयः। अयं।
न। हियानः। अभि। वाजं। अर्ष। स्वःऽवित्। कोशं। दिवः। अद्रिऽमातरं। वृषा। पवित्रे। अधि। सानौ। अव्ये।
सोमः। पुनानः। इंद्रियं। धायसा। प्र। ते। आश्विनीः। पवमान। धीऽजुवः। दिव्याः। असृग्रं। पयसा। ध
या

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ रीमणि। प्र। अंतः। ऋषयः। स्थाविरीः। असृक्षत। ये। त्वा। मृजंति। ऋषिऽसान। वेधसः। विश्वा। धामानि।
३२ विश्वऽचक्षः। ऋभ्वसः। प्रऽभोः। ते। सतः। परि। यंति। केतवः। विऽआनशिः। पवसे। सोम। धर्मऽभिः। पतिः।
विश्वस्य। भुवनस्य। राजसि॥ ३१॥ उभयतः। पवमानस्य। रश्मयः। ध्रुवस्य। सतः। परि। यंति। केतवः।
यदि। पवित्रे। अधि। मृज्यते। हरिः। सत्ता। नि। योना। कलशेषु। सीदति। यज्ञस्य। केतुः। पवते। सुऽअध्व
रः। सोमः। देवानां। उप। याति। निःऽकृतं। सहस्रऽधारः। परि। कोशं। अर्षति। वृषा। पवित्रं। अति। एति।
रोरुवत्। राजा। समुद्रं। नद्यः। वि। गाहते। अपां। ऊर्मिं। सचते। सिंधुषु। श्रितः। [illegible]। अधि। अस्था
त्। सानु। पवमानः। अव्ययं। नाभा। पृथिव्याः। धरुणः। महः। दिवः। दिवः। ना। सानु। स्तनयन्। अचि ३२

© Dharmartha Trust J&K. Digitized by eGangotri

क्रदत्। द्यौः। च। यस्य। पृथिवी। च। धर्मऽभिः। इंद्रस्य। सख्यं। पवते। विऽवेविदत्। सोमः। पुनानः। कलशेषु।
सीदति। ज्योतिः। यज्ञस्य। पवते। मधु। प्रियं। पिता। देवानां। जनिता। विभुऽवसुः। दधाति। रत्नं। स्वधयोः। अ
पीच्यं। मदिन्ऽतमः। मत्सरः। इंद्रियः। रसः॥ ३३॥ अभिऽक्रंदन्। कलशं। वाजी। अर्षति। पतिः। दिवः। शतऽधा
रः। विऽचक्षणः। हरिः। मित्रस्य। सदनेषु। सीदति। मर्मृजानः। अविऽभिः। सिंधुऽभिः। वृषा। अग्रे। सिंधूनां।
पवमानः। अर्षति। अग्रे। वाचः। अग्रियः। गोषु। गच्छति। अग्रे। वाजस्य। भजते। महाऽधनं। सुऽआयुधः। सो
तृऽभिः। पूयते। वृषा। अयं। मतऽवान्। शकुनः। यथा। हितः। अव्यः। ससार। पवमानः। ऊर्मिणा। तव। क्र
त्वा। रोदसी इति। अंतरा। कवे। शुचिः। धिया। पवते। सोमः। इंद्र। ते। द्रापिं। वसानः। यजतः। दिविऽस्पृशं। अं

© Dharmartha Trust J&K. Digitized by eGangotri

१·स· तरिक्षऽप्राः । भुवनेषु । अर्पितः । स्वः । जज्ञानः । नभसा । अभि । अक्रमीत् । प्रत्नं । अस्य । पितरं । आ । विवासति ।
३३ सः । अस्य । विशे । महि । शर्म । यच्छति । यः । अस्य । धाम । प्रथमं । विऽआनशे । पदं । यत् । अस्य । परमे । विऽओम
नि । अतः । विश्वाः । अभि । सं । याति । संऽयतः ॥ १५ ॥ प्रो इति । अयासीत् । इंदुः । इंद्रस्य । निःऽकृतं । सखा । स
ख्युः । न । प्र । मिनाति । संऽगिरं । मर्यःऽइव । युवतिऽभिः । सं । अर्षति । सोमः । कलशे । शतऽयाम्ना । पथा । प्र । वः ।
धियः । मंद्रऽयुवः । विपन्युवः । पनस्युवः । संऽवसनेषु । अक्रमुः । सोमं । मनीषाः । अभि । अनूषत । स्तुभः । अ
भि । धेनवः । पयसा । ईं । अशिश्रयुः । आ । नः । सोम । संऽयतं । पिप्युषीं । इषं । इंदो इति । पवस्व । पवमान । अस्रि
धं । या । नः । दोहते । त्रिः । अहन् । असश्चुषी । क्षुऽमत् । वाजऽवत् । मधुऽमत् । सुऽवीर्यं । वृषा । मतीनां । पवते । ३३

© Dharmartha Trust J&K. Digitized by eGangotri

विऽचक्षणः। सोमः। अन्हः। प्रऽतरीता। उषसः। दिवः। क्राणा। सिंधूनां। कलशान्। अवीवशत्। इंद्रस्य। हार्दि।
आऽविशन्। मनीषिऽभिः। मनीषिऽभिः। पवते। पूर्व्यः। कविः। नृऽभिः। यतः। परि। कोशान्। अचिक्रदत्। त्रित
स्य। नाम। जनयन्। मधु। क्षरन्। इंद्रस्य। वायोः। सख्याय। कर्तवे।।३६।। अयं। पुनानः। उषसः। विऽरोच
यत्। अयं। सिंधुऽभ्यः। अभवत्। ऊं इति। लोकऽकृत्। अयं। त्रिः। सप्त। दुदुहानः। आऽशिरं। सोमः। हृदे। पव
ते। चारु। मत्सरः। पवस्व। सोम। दिव्येषु। धामऽसु। सृजानः। इंदो इति। कलशे। पवित्रे। आ। सीदन्। इंद्रस्य।
जठरे। कनिक्रदत्। नृऽभिः। यतः। सूर्यं। आ। अरोहयः। दिवि। अद्रिऽभिः। सुतः। पवसे। पवित्रे। आ। इंदोइ
ति। इंद्रस्य। जठरेषु। आऽविशन्। त्वां। नृऽचक्षाः। अभवः। विऽचक्षण। सोम। गोत्रं। अंगिरःऽभ्यः। अवृणोः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. अप।त्वां।सोमम्।पवमानं।स्वऽआध्यः।अनु।विप्रासः।अमदन्।अवस्यवः।त्वां।सुऽपर्णः।आ।अभरत्।दिवः।
३४ परि।इंद्रो इति।विश्वाभिः।मतिऽभिः।परिऽकृतं।अव्ये।पुनानं।परि।वारे।ऊर्मिणा।हरिं।नवंते।अभि।सप्त।
धेनवः।अपां।उपऽस्थे।अधि।आयवः।कविं।ऋतस्य।योना।महिषाः।अहेषत।।३।।इंदुः।पुनानः।अति।
34 गाहते।मृधः।विश्वानि।कृण्वन्।सुऽपथानि।यज्यवे।गाः।कृण्वानः।निःऽनिजं।हर्यतः।कविः।अत्यः।न।
क्रीळन्।परि।वारं।अर्षति।असश्चतः।शतऽधाराः।अभिऽश्रियः।हरिं।नवंते।अव।ताः।उदन्युवः।क्षिपः।
मृजंति।परि।गोभिः।आऽवृतं।तृतीये।पृष्ठे।अधि।रोचने।दिवः।तव।इमाः।प्रऽजाः।दिव्यस्य।रेतसः।त्वं।
विश्वस्य।भुवनस्य।राजसि।अथ।इदं।विश्वं।पवमान।ते।वशे।त्वं।इंदो इति।प्रथमः।धामऽधाः।असि। ३४

© Dharmartha Trust J&K. Digitized by eGangotri

त्वं।समुद्रः।असि।विश्वऽवित्।कवे।तव।इमाः।पंच।प्रऽदिशः।विऽधर्मणि।त्वं।द्यां।च।पृथिवीं।च।अति।
जभ्रिषे।तव।ज्योतींषि।पवमान।सूर्यः।त्वं।पवित्रे।रजसः।विऽधर्मणि।देवेभ्यः।सोम।पवमान।पूय
से।त्वां।उशिजः।प्रथमाः।अगृभ्णत।तुभ्य।इमा।विश्वा।भुवनानि।येमिरे॥१७॥प्र।रेभः।एति।अति।
वारं।अव्ययं।वृषा।वनेषु।अव।चक्रदत्।हरिः।सं।धीतयः।वावशानाः।अनूषत।शिशुं।रिहंति।मत
यः।पनिप्नतं।सः।सूर्यस्य।रश्मिऽभिः।परि।व्यत।तंतुं।तन्वानः।त्रिऽवृतं।यथा।विदे।नयन्।ऋतस्य।
प्रऽशिषः।नवीयसीः।पतिः।जनीनां।उप।याति।निःऽकृतं।राजा।सिंधूनां।पवते।पतिः।दिवः।ऋ
तस्य।याति।पथिऽभिः।कनिक्रदत्।सहस्रऽधारः।परि।सिच्यते।हरिः।पुनानः।वाचं।जनयन्।उ

© Dharmartha Trust J&K. Digitized by eGangotri

न।
प.स. उपऽवसुः। पवमान। महि। अर्णः। वि। धावसि। सूरः। चित्रः। अव्ययानि। पव्यया। गभस्तिऽपूतः। नृऽ
३५ भिः। अद्रिऽभिः। सुतः। महे। वाजाय। धन्याय। धन्वसि। इषं। ऊर्जं। पवमान। अभि। अर्षसि। श्येनः। न।
35 वंसु। कलशेषु। सीदसि। इंद्राय। मद्वा। मद्यः। मदः। सुतः। दिवः। विष्टंभः। उपऽमः। विऽचक्षणः॥ ३८॥ सप्त।
स्वसारः। अभि। मातरः। शिशुं। नवं। जज्ञानं। जेन्यं। विपःऽचितं। अपां। गंधर्वं। दिव्यं। नृऽचक्षसं। सोमं।
विश्वस्य। भुवनस्य। राजसे। ईशानः। इमा। भुवनानि। वि। ईयसे। युजानः। इंदो इति। हरितः। सुऽ
पर्ण्यः। ताः। ते। क्षरंतु। मधुऽमत्। घृतं। पयः। तव। व्रते। सोम। तिष्ठंतु। कृष्टयः। त्वां। नृऽचक्षः। असि।
सोम। विश्वतः। पवमान। वृषभ। ता। वि। धावसि। सः। नः। पवस्व। वसुऽमत्। हिरण्यऽवत्। वयं। स्या ३५

© Dharmartha Trust J&K. Digitized by eGangotri

मा। भुवनेषु। जीवसे। गोऽवित्। पवस्व। वसुऽवित्। हिरण्यऽवित्। रेतःऽधाः। इंदो इति। भुवनेषु। अर्पितः। त्वं।
सुऽवीरः। असि। सोम। विश्वऽवित्। तं। त्वा। विप्राः। उप। गिरा। इमे। आसते॥ उत्। मध्वः। ऊर्मिः। वननाः।
अति। स्थित्। पवते। अपः। वसानः। महिषः। वि। गाहते। राजा। पवित्रऽरथः। वाजं। आ। अरुहत्। सहस्रऽभृ
ष्टिः। जयति। श्रवः। बृहत्॥ १०॥ सः। मंदना। उत्। इयर्ति। प्रजाऽवतीः। विश्वऽआयुः। विश्वाः। सुऽभराः।
अहःऽदिवि। प्रस्ना। प्रजाऽवंतं। रयिं। अश्वऽवत्यं। पीतः। इंदो इति। इंद्रं। अस्मभ्यं। याचतात्। सः। अग्रे।
अन्हां। हरिः। हर्यतः। मदः। प्र। चेतसा। चेतयते। अनु। द्युऽभिः। द्वा। जना। यातयन्। अंतः। ईयते। नरा।
शंसं। च। दैव्यं। च। धर्तरि। अंजते। वि। अंजते। सं। अंजते। क्रतुं। रिहंति। मधुना। अभि। अंजते। सिंधोः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. उत्ऽश्वासः । पतयंत । उक्षणः । हिरण्यऽपावाः । पशुं । आ । सुगृभ्णते । विपःऽचिते । पवमानाय । गायत । म
३६ ही । न । धारा । अति । अंधः । अर्षति । अहिः । न । जूर्णां । अति । सर्पति । त्वचं । अत्यः । न । क्रीडन् । असरत् ।
वृषा । हरिः । अग्नेऽगाः । राजा । अव्यः । न विव्यते । विऽमानः । अन्हां । भुवनेषु । अर्पितः । हरिः । घृतऽस्नुः ।
सुऽदृशीकः । अर्णवः । ज्योतिःऽरथः । पवते । राये । ओक्यः ॥ २० ॥ असर्जि । स्कंभः । दिवः । उत्ऽयतः । मदः ।
परि । त्रिऽधातुः । भुवनानि । अर्षति । अंशुं । रिहंति । मतयः । पनिप्नतं । गिरा । यदि । निःऽनिजं । ऋग्मि
णः । ययुः । म्राते । धाराः । अति । अण्वानि । मेष्यः । पुनानस्य । संऽयतः । यंति । रंहयः । यत्र । गोभिः । इंदो इ
ति । चम्वोः । संऽअज्यसे । आ । सुवानः । सोम । कलशेषु । सीदसि । पवस्व । सोम । क्रतुऽवित्तमः । उ ३६

नी

© Dharmartha Trust J&K. Digitized by eGangotri

वृहद्देम्त विदथेषु वीराः

स्थ्यः॥ अव्यः॥ वारे॥ परि॥ धाव॥ मधु॥ प्रियं॥ जहि॥ विश्वा॥ न्॥ रक्षसः॥ इंदो इति॥ अत्रिणः॥ ५॥ २॥ आ॥ प्र॥ तु॥ द्रव॥ परि॥ कोशं॥ नि॥ सीद॥ नृऽभिः॥ पुनानः॥ अभि॥ वाजं॥ अर्ष॥ अश्वं॥ न॥ त्वा॥ वाजिनं॥ मर्जयंतः॥ अछ॥ बर्हिः॥ रशनाभिः॥ नयंति॥ सुऽआयुधः॥ पवते॥ देवः॥ इंदुः॥ अशस्तिऽहा॥ वृजनं॥ रक्षमाणः॥ पिता॥ देवानां॥ जनिता॥ सुऽदक्षः॥ विष्टंभः॥ दिवः॥ धरुणः॥ पृथिव्याः॥ ऋषिः॥ विप्रः॥ पुरःऽएता॥ जनानां॥ ऋभुः॥ धीरः॥ उशना॥ काव्येन॥ सः॥ चित्॥ विवेद॥ निऽहितं॥ यत्॥ आसां॥ अपीच्यं॥ गुह्यं॥ नाम॥ गोनां॥ एषः॥ स्यः॥ ते॥ मधुऽमा न्॥ इंद्र॥ सोमः॥ वृषा॥ वृष्णे॥ परि॥ पवित्रे॥ अक्षारिति॥ सहस्रऽसाः॥ शतऽसाः॥ भूरिऽदावा॥ शश्वत्ऽत मं॥ बर्हिः॥ आ॥ वाजी॥ अस्थात्॥ एते॥ सोमाः॥ अभि॥ गव्या॥ सहस्रा॥ महे॥ वाजाय॥ अमृताय॥ श्रवांसि॥

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ पवित्रेभिः। पवमानाः। असृग्रन्। श्रवस्यवः। न। पृतनाजः। अत्याः॥ २२॥ परि। हि। स्म। पुरुऽहूतः। जना

२० नां। विश्वा। असरत्। भोजना। पूयमानः। अथ। आ। भर। श्येनऽभृत। प्रयांसि। रयिं। तुंजानः। अभि। वा

जं। अर्ष। एषः। सुवानः। परि। सोमः। पवित्रे। सर्गः। न। सृष्टः। अदधावत्। अर्वा। तिग्मे इति। शिशानः। म

37 हिषः। न। शृंगे इति। गाः। गव्यन्। अभि। शूरः। न। सत्वा। एषा। आ। ययौ। परमात्। अंतः। अद्रेः। कूचित्। स

तीः। ऊर्वे। गाः। विवेद। दिवः। न। विऽद्युत्। स्तनयंती। अभ्रैः। सोमस्य। ते। पवते। इंद्र। धारा। उत। स्म। राशिं।

परि। यासि। गोनां। इंद्रेण। सोम। सऽरथं। पुनानः। पूर्वीः। इषः। बृहतीः। जीरदानो इति जीरऽदानो। शि

क्ष। शचीऽवः। तव। ताः। उपऽस्तुत्॥ २३॥ नु। मंद्यः। पवते। त्वं। अस्य। पाहि। त्वं। आहार्यं। चकृषे। त्वं। ववृषे। इंदुं। ३७

ॐ तं [illegible]

© Dharmartha Trust J&K. Digitized by eGangotri

मदाय।युज्याय।सोमः॥सः।ईं।रथः।न।भुरिषाट्।अयोजि।महः।पुरूणि।सातये।वसूनि।आत्।ईं।विश्वा।
नहुष्याणि।जाता।स्वःऽसाता।वने।ऊर्ध्वा।नवंत।वायुः।न।यः।नियुत्वान्।इष्टऽयामा।नासत्याऽइव।ह
वे।आ।शंऽभविष्ठः।विश्वऽवारः।द्रविणोदाःऽइव।त्मन्।पूषाऽइव।धीऽजवनः।असि।सोम॥इंद्रः।न।
यः।महा।कर्माणि।चक्रिः।हंता।वृत्राणां।असि।सोम।पूःऽभित्।पेद्वः।न।हि।त्वं।अहिऽनाम्नां।हंता।
विश्वस्य।असि।सोम।दस्योः॥अग्निः।न।यः।वने।आ।सृज्यमानः।वृथा।पाजांसि।कृणुते।नदीषु।
जनः।न।युध्वा।महतः।उपब्दिः।इयर्ति।सोमः।पवमानः।ऊर्मिं॥एते।सोमाः।अति।वाराणि।अव्या।
दिव्याः।न।कोशासः।अभ्रऽवर्षाः।वृथा।समुद्रं।सिंधवः।न।नीचीः।सुतासः।अभि।कलशान्।असृ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ ग्रन्नाशुष्मी।शार्ङ्गः।ना।मारुतं।पवस्व।अनभिऽशस्ता।दिव्या।यथा।विट्।आपः।ना।मक्षु।सुऽमतिः।भव।नः॥

३८ सहस्रऽअप्साः।पृतनाषाट्।ना।यज्ञः।गोऽरस्या।ग्रोइति।स्वः।वर्हिः।पथ्याभिः।अस्यात्।दिवः।ना।वृष्टिः।

पवमानः।अक्षारिति।सहस्रऽधारः।असदत्।नि।अस्मेइति।मातुः।उपऽस्थे।वने।आ।च।सोमः।राजा।सिं

धूनां।अवुसिष्ट।वासः।ऋतस्य।नावं।आ।अरुहत्।रजिष्ठां।अप्ऽसु।द्रप्सः।ववृधे।श्येनऽजूतः।दुहे।ईं

पिता।दुहे।ईं।पितुः।जां।सिंहान।संतां।मध्वः।अयासं।हरिं।अरुषं।दिवः।अस्य।पतिं।शूरः।युत्ऽसु।प्रथमः।

पृच्छते।गाः।अस्य।चक्षसा।परि।पाति।उक्षा।मधुऽपृष्ठं।घोरं।अयासं।अश्वं।रथे।युंजं।ति।उरुऽचक्रं।ऋ

ष्वं।सखसारः।ईं।आमयः।मर्जयंति।सऽनाभयः।वाजिनं।ऊर्जयंति।चतस्रः।ईं।घृतऽदुहः।सचंते।समाने।अं ३९

38

© Dharmartha Trust J&K. Digitized by eGangotri

तः।धरुणे।नि।ऽसत्ताः।ताः।ई।अर्षन्ति।नमसा।पुनानाः।ताः।ई।विश्वतः।परि।सन्ति।पूर्वीः।विऽस्तंभः।दिवः।

धरुणः।पृथिव्याः।विश्वाः।उत।क्षितयः।हस्ते।अस्य।असत्।त्रा।ते।उत्सः।गृणते।नियुत्वान्।मध्वः।अंशुः।

पवते।इन्द्रियाय।वन्वन्।अर्वातः।अभि।देवऽवीतिं।इन्द्राय।सोम।वृत्रऽहा।पवस्व।शग्धि।महः।पुरुऽचन्द्र

स्य।रायः।सुऽवीर्यस्य।पतयः।स्याम॥२५॥प्र।हिन्वानः।जनिता।रोदस्योः।रथः।न।वाजं।सनिष्यन्।अ नि

अयासीत्।इन्द्रं।गच्छन्।आयुधा।संऽशिशानः।विश्वा।वसु।हस्तयोः।आऽदधानः।अभि।त्रिऽपृष्ठं।वृ

षणं।वयःऽधां।आंगूषाणां।अवावशन्त।वाणीः।वना।वसानः।वरुणः।न।सिन्धून्।वि।रत्नऽधाः।दय

ते।वार्याणि।शूरऽग्रामः।सर्वऽवीरः।सहावान्।जेता।पवस्व।सनिता।धनानि।तिग्मऽआयुधः।क्षि

© Dharmartha Trust J&K. Digitized by eGangotri

39

प॰स॰ ग्रः। धन्वा। समतःऽसु। अषाळ्हः। सक्रान्। पृतनासु। शत्रून्। उरुऽगव्यूतिः। अभया। नि। कृण्वन्। समीची

३९ नेइति सं॒ऽईचीने। आ। पवस्व। पुरंधीइति पुरंऽधी। अप। सिसासन्। उषसः। स्वः। गाः। सं। चिक्रदः। मु

हः। अस्मभ्यं। वाजान्। मत्सि। सोम। वरुणं। मत्सि। मित्रं। मत्सि। इंद्रं। इंदोइति। पवमान। विष्णुं। मत्सि।

शर्द्धः। मारुतं। मत्सि। देवान्। मत्सि। महां। इंद्रं। इंदोइति। मदाय। एव। राजाऽइव। क्रतुऽमान्। अमेन। वि

श्वा। घनिघ्नत्। दुःऽइता। पवस्व। इंदोइति। सुऽउक्ताय। वचसे। वयः। धाः। ॥२॥ इति सप्तमाष्टके तृती सूयं॰

योऽध्यायः॥ ॥ओं नमः॥ असर्जि। कश्यपः। परिऽसुवानः। साकमुक्षः। पंच। नोधा। अपि। यः। कण्वः। कंकृतिश्र नि

स्कण्वः। प्र। सेनानीः। चतुर्विंशतिर्दैवोदासिः। प्रतर्दनोऽस्य प्रेषा। पंचाराऽदाघेत्र चंवासिष्ठोपरश्यदुत्त ३९

© Dharmartha Trust J&K. Digitized by eGangotri

रोनवप्रथगवस्विइंद्रप्रमतिर्ऋषगणोमन्युस्तपमन्युर्व्यांघ्रपाछक्तिःकर्णश्रुन्मृळीकोवसुक्रइति
चतुर्दशापराशरोत्याःकुत्सोभिनोद्वादशांबरीषऋजिश्वाचानुष्टुभंहव्यहत्युपांत्याहर्यंतायाष्टोरे
भस्तन्नकाश्यपौबृहत्याघामीनवंतेनव॥७६॥असर्जि।वक्वा।रथ्ये।यथा।आजौ।धिया।मनोता।
प्रथमः।मनीषी।दश।स्वसारः।अधि।सानौ।अव्ये।अजंति।वन्हिं।सदनानि।अच्छ।वीती।जनस्य।
दिव्यस्य।कव्यैः।अधि।सुवानः।नहृव्येभिः।इंदुः।प्रायः।नृऽभिः।अमृतः।मर्त्यैभिः।मर्मृजानः।अवि
ऽभिः।गोभिः।अत्ऽभिः।रषा।वृषे।रोरुवत्।अंशुः।अस्मै।पवमानः।हरा।त्रा।ईर्ते।पयः।गोः।सह
स्रं।ऋक्वा।पथिऽभिः।वचःऽवित्।अध्वस्मऽभिः।सूरः।अण्वं।वि।याति।रजः।दक्षा।चितार्।क्षसः।

© Dharmartha Trust J&K. Digitized by eGangotri

प. स. सदांसि।पुनानः।इंदो इति।ऊर्णुहि।वि।वाजान्।रक्ष।उपरिष्टात्।तुजता।वधेन।यः।अंति।दूरात्।

४० उपऽनायं।एषां।सः।प्रत्नऽवत्।नव्यसे।विश्वऽवार।सुऽउक्ताय।पथः।कृणुहि।प्राचः।यः।दुःऽसहः।सः।

वनुषा।बृहंतः।तान्।ते।अरयाम।पुरुऽकृत।पुरुक्षो इति पुरुऽक्षो।एव।पुनानः।अपः।स्वः।गाः।अस्म

40 भ्यं।तोका।तनयानि।भूरि।शं।नः।क्षेत्रं।उरु।ज्योतींषि।सोम।ज्योक्।नः।सूर्यं।दृशये।रिरीहि।३।

परि।सुवानः।हरिः।अंशुः।पवित्रे।रथः।न।सर्जि।सनये।हियानः।आपत्।श्लोकं।इंद्रियं।पूयमानः।

प्रति।देवान्।अजुषत।प्रयःऽभिः।अच्छ।नृऽचक्षाः।असरत्।तो।नाम।दधानः।कविः।अस्य।योनौ।सी

दन्।होताऽइव।सदना।चमूषु।उप।ईं।अग्मन्।ऋषयः।सप्त।विप्राः।प्र।सुऽमेधाः।गातुऽवित्।विश्वऽ ४०

पवित्रे।

© Dharmartha Trust J&K. Digitized by eGangotri

देवः।सोमः।पुनानः।सदः।एति।नित्यं।भुवत्।विश्वेषु।काव्येषु।रंता।अनु।जनान्।यतते।पंच।धीरः।त
वा।त्ये।सोम।पवमान।निण्ये।विश्वे।देवाः।त्रयः।एकादशासः।दश।स्वधाभिः।अधि।सानौ।अव्ये।
मृजंति।त्वा।नद्यः।सप्त।यह्वीः।तत्।नु।सत्यं।पवमानस्य।अस्तु।यत्र।विश्वे।कारवः।संऽनसंत।ज्यो
तिः।यत्।अह्ने।अकृणोत्।ऊं इति।लोकं।प्र।आवत्।मनुं।दस्यवे।कः।अभीकं।परि।सद्मऽइव।पशु
मंति।होता।राजा।न।सत्यः।संऽइतीः।इयानः।सोमः।पुनानः।कलशान्।अयासीत्।सीदन्।मृगः।
न।महिषः।वनेषु।२।साकंऽउक्षः।मर्जयंत।स्वसारः।दश।धीरस्य।धीतयः।धनुत्रीः।हरिः।परि।
अद्रवत्।जाः।सूर्यस्य।द्रोणं।ननक्षे।अत्यः।न।वाजी।सं।मातृऽभिः।न।शिशुः।वावशानः।वृषा।

© Dharmartha Trust J&K. Digitized by eGangotri

पृ. स. ऽधन्वा । पुरुऽवारः । अत्यऽभिः । मर्यः । न । योषां । अभि । निःऽकृतं । यन् । सं । गच्छते । कलशे । उस्रियाभिः ।
४३ उत । प्र । पिप्ये । ऊधः । अघ्न्यायाः । इंदुः । धाराभिः । सचते । सुऽमेधाः । मूर्धानं । गावः । पयसा । चमूषु । अभि ।
भि । श्रीणंति । वसुऽभिः । न । निक्तैः ॥ सः । नः । देवेभिः । पवमान । रद । इंदो इति । रयिं । अश्विनं । वावशानः ।
41 रथिरायतां । उशती । पुरंऽधिः । अस्मद्र्यक् । आ । दावने । वसूनां ॥ नु । नः । रयिं । उप । मास्व । नृऽवंतं । पुना
नः । वाताप्यं । विश्वऽचंद्रं । प्र । वंदितुः । इंदो इति । तारि । आयुः ॥ ० ॥ ३ ॥ अधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । ग्रातर्मू क्ष्मापि३
स्पर्धंते । धियः । सूर्ये । न । विशः । अपः । वृणानः । पवते । कविऽयन् । व्रजं । न । पशुऽवर्धनाय । मन्म ॥ द्वि राम:
ता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथंत ॥ धियः । पिन्वानाः । स्वसरे । न । गावः । ऋत ४३

© Dharmartha Trust J&K. Digitized by eGangotri

तऽयेतीः। अभि। नाव। श्रे। इंदुः। परि। यत्। कविऽभिः। काव्या। भरते। भरः। न। रथः। भुवनानि। विश्वा। देवेषु। य
शः। मर्तीय। भूषन्। दक्षाय। रायः। पुरुऽभूषु। नव्यः। श्रियः। जातः। श्रिये। आ। निः। इयाय। श्रियं। वयः।
जरितृऽभ्यः। दधाति। श्रियं। वसानाः। अमृतऽत्वं। आयन्। भवंति। सत्या। संऽइथा। मितऽद्रौ। इषं। ऊर्जं।
अभि। अर्ष। अश्व्यं। गां। उरु। ज्योतिः। कृणुहि। मत्सि। देवान्। विश्वानि। हि। सुऽसहा। तानि। तुभ्यं। पव
मान। बाधसे। सोम। शत्रून्। रा। कनिक्रंति। हरिः। आ। सृज्यमानः। सीदन्। वनस्य। जठरे। पुनानः।
नृऽभिः। यतः। कृणुते। निःऽनिजं। गाः। अतः। मतीः। जनयत। स्वधाभिः। हरिः। सृजानः। पथ्यां। ऋत
स्य। देवः। देवानां। गुह्यानि। नाम। आविः। कृणोति। बर्हिषि। प्रऽवाचे। अपांऽइव। इत्। ऊर्मयः। त
इयर्त्तिवाच्चमरितेवनावं

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. तुरा।पाः।प्रा।मनीषाः।ईरते।सोमं।अछ।नमस्यंतीः।उप।चायंति।सं।च।आ।च।विशंति।उशतीः।उशंतं।
४२ तं।मर्मृजानं।महिषं।न।सानौ।अंशुं।दुहंति।उक्षणं।गिरिष्ठां।तं।वावशानं।मतयः।सचंते।त्रितः।बि
भर्ति।वरुणं।समुद्रे।इष्यन्।राजा।चोकुवक्रतः।इया।होतुः।पुनानः।इंद्रो।इति।वि।स्याम।मनीषां।इंद्रः।चायत्र।
स्यधः।सोमगा।या।सुवीर्यस्य।पतयः।स्याम।पा।प्रा।सेनानीः।शूरः।अग्रे।रथानां।गव्यन्।एति।
हर्षंते।अस्य।सेनाः।भद्राः।कृण्वन्।इंद्रहवान्।सखिभ्यः।आ।सोमः।वस्रा।रभसानि।दत्ते।सं।अ
स्य।हरिः।हरयः।मजंति।अश्वहयैः।अनिशितं।नमोभिः।आ।तिष्ठति।रथं।इंद्रस्य।सखा।विद्वान्।ए
ना।सुमतिं।याति।अछ।सः।नः।देवा।देवता।ता।पवस्व।महे।सोम।प्सरसे।इंद्रपानः।कृण्वन्।अपः।व ४२

© Dharmartha Trust J&K. Digitized by eGangotri

र्षयन्त।घा।उत।इमां।उरोः।आ।नः।वरिवस्य।पुनानः।अजीतये।अहतये।पवस्व।स्वस्तये।सर्वऽतातये।बृहते।न
तः।उ।शंतिः।विश्वे।इमे।सखायः।नतः।अहं।वशिम।पवमानः।सोमः।सोमः।पवते।जनिता।मतीनां।जनिता।दि
वः।जनिता।पृथिव्याः।जनिता।अग्नेः।जनिता।सूर्यस्य।जनिता।इंद्रस्य।जनिता।उत।विष्णोः।घा।ब्रह्मा।देवा
नां।पदऽवीः।कवीनां।ऋषिः।विप्राणां।महिषः।मृगाणां।श्येनः।गृध्राणां।स्वऽधितिः।वनानां।सोमः।पवि
त्रं।अति।एति।रेभन्।प्र।अवीवपत।वाचः।ऊर्मिं।न।सिंधुः।गिरः।सोमः।पवमानः।मनीषाः।अंतरिति।
पश्यन्।वृजना।इमा।अवराणि।आ।तिष्ठति।वृषभः।गोषु।जानन्।सः।मत्सरः।पृत्ऽसु।वन्वन्।अवातः।
सहस्रऽरेताः।अभि।वाजं।अर्ष।इंद्राय।इंद्राय।इंदो।इति।पवमानः।मनीषी।अंशोः।ऊर्मिं।ईरय।गाः।इषण्यन्।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स.४ परि।प्रियः।कलशे।देवऽवातः।इंद्राय।सोमः।रण्यः।मदाय।सहस्रऽधारः।शतऽवाजः।इंदुः।वाजी।न।सप्तिः।स
४३ मना।जिगाति।सः।पूर्व्यः।वसुऽवित्।जायमानः।मृजानः।अप्ऽसु।दुदुहानः।अद्रौ।अभिशस्तिऽपाः।भुव
नस्य।राजा।विदत्।गातुं।ब्रह्मणे।पूयमानः।।७।।त्वया।हि।नः।पितरः।सोम।पूर्वे।कर्माणि।चक्रुः।पवमा
न।धीराः।वन्वन्।अवातः।परिऽधीन्।अप।ऊर्णु।वीरेभिः।अश्वैः।मघऽवा।भव।नः।यथा।अवर्वथाः।म
नवे।वयःऽधाः।अमित्रऽहा।वरिवःऽवित्।हविष्मान्।एव।पवस्व।द्रविणं।दधानः।इंद्रे।सं।तिष्ठ।जन
य।आयुधानि।पवस्व।सोम।मधुऽमान्।ऋतऽवा।अपः।वसानः।अधि।सानौ।अव्ये।अव।द्रोणानि। रामोहरिः
घृतऽवंति।सीद।मदिन्ऽतमः।मत्सरः।इंद्रऽपानः।वृष्टिं।दिवः।शतऽधारः।पवस्व।सहस्रऽसाः।वाजऽयुः। ४३

© Dharmartha Trust J&K. Digitized by eGangotri

द्रवऽवीतौ। सं। सिंधुऽभिः। कलशैः। वावशानः। सं। उस्रियाभिः। प्रऽतिरन्। नः। आयुः। एषः। स्यः। सोमः। मतिऽभिः।
पुनानः। अस्रः। न। वाजी। तरति। इत्। अरातीः। पयः। न। दुग्धं। अदितेः। इषिरं। उरुऽइव। गातुः। सुऽयमः। न। वोळ्हा।
॥८॥ स्वऽआयुधः। सोतृऽभिः। पूयमानः। अभि। अर्ष। गुह्यं। चारु। नाम। अभि। वाजं। सप्तिःऽइव। श्रवस्या। अभि।
वायुं। अभि। गाः। देव। सोम। शिशुं। जज्ञानं। हर्यतं। मृजंति। शुंभंति। वह्निं। मरुतः। गणेन। कविः। गीःऽभिः। काव्येन।
कविः। सन्। सोमः। पवित्रं। अति। एति। रेभन्। ऋषिः। मनाः। यः। ऋषिऽकृत्। स्वःऽसाः। सहस्रऽनीथः। पदऽवीः।
कवीनां। तृतीयं। धाम। महिषः। सिसासन्। सोमः। विऽराजं। अनु। राजति। स्तुप्। चमूऽसत्। श्येनः। शाकुनः। विऽभृ
त्वा। गोऽविंदुः। द्रप्सः। आयुधानि। बिभ्रत्। अपां। ऊर्मिं। सचमानः। समुद्रं। तुरीयं। धाम। महिषः। विवक्ति। अपां।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ मर्यः।न।शुभ्रः।तन्वं।मृजानः।अत्यः।न।सृत्वा।सनये।धनानां।वृषाऽइव।यूथा।परि।कोशं।अर्षन्।कनिक्रदत्।
४४ चम्वोः।आ।विवेश।।१।।पवस्व।इंदो इति।पवमानः।महःऽभिः।कनिक्रदत्।परि।वाराणि।अर्ष।क्रीळन्।चम्वोः।
आ।विश।पूयमानः।इंद्रं।ते।रसः।मदिरः।ममत्तु।प्र।अस्य।धाराः।बृहतीः।असृग्रन्।अक्तः।गोभिः।कलशा
न्।आ।विवेश।सामा।कृण्वन्।सामन्यः।विपःऽचित्।क्रंदन्।एति।अभि।सख्युः।न।जामिं।अपः।घ्नन्।एषि।
पवमान।शत्रून्।प्रियां।न।आरः।अभिऽगीतः।इंदुः।सीदन्।वनेषु।शकुनः।न।पत्वा।सोमः।पुनानः।कलशे
षु।सत्ता।आ।ते।रुचः।पवमानस्य।सोम।योषाऽइव।यंति।सुऽदुघाः।सुऽधाराः।हरिः।आऽनीतः।पुरुऽवारः।
अप्ऽसु।अचिक्रदत्।कलशे।देवऽयूनां।।१०।।अस्य।प्रेषा।हेमना।पूयमानः।देवः।देवेभिः।सं।अपृक्त।रसं। ४४

© Dharmartha Trust J&K. Digitized by eGangotri

सुतः। पवित्रं। परि। एति। रेभन्। मिताऽइव। सद्म। पशुऽमंति। होता॥ भद्रा। वस्त्रा। सम्ऽअन्या। वसानः। महान्। कविः।
निऽवचनानि। शंसन्॥ आ। वच्यस्व। चम्वोः। पूयमानः। विऽचक्षणः। जागृविः। देवऽवीतौ॥ सं॥ ऊं इति। प्रियः। मृज्य
ते। सानौ। अव्ये। यशःऽतरः। यशसां। क्षैतः। अस्मे इति। अभि। स्वर। धन्व। पूयमानः॥ ३॥ प्र। गायत। अभि। अर्चा। यूयं पात०
नो म। देवान्। सोमं। हिनोत। महते। धनाय। स्वादुः। पवाते। अति। वारं। अव्यं। आ। सीदाति। कलशं। देवऽयुः। नः।
इंदुः। देवानां। उप। सख्यं। आऽयन्। सहस्रऽधारः। पवते। मदाय। नृऽभिः। स्तवानः। अनु। धाम। पूर्वं। अगन्।
इंद्रं। महते। सौभगाय॥ ४॥ स्तोत्रे। राये। हरिः। अर्ष। पुनानः। इंद्रं। मदः। गच्छतु। ते। भराय। देवैः। याहि। सऽरथं।
यूयं पात० राधः। अच्छ॥ ५॥ प्र। काव्यं। उशनाऽइव। ब्रुवाणः। देवः। देवानां। जनिम। विवक्ति। महिऽव्रतः। शुचिऽबंधुः। पावक

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ कः। पदा। वराहः। अभि। एति। रेभन्। प्र। हंसासः। तृपलं। मन्युं। अछ। अमात्। अस्तं। वृषऽगणाः। अयासुः।
४५ आंगूष्यं। पवमानं। सखायः। दुःऽमर्षं। साकं। प्र। वदंति। वाणं। सः। रंहते। उरुऽगायस्य। जूतिं। वृथा। क्रीळंतं।
मिमते। न। गावः। परीणसं। कृणुते। तिग्मऽशृंगः। दिवा। हरिः। ददृशे। नक्तं। ऋज्रः। इंदुः। वाजी। पवते। गोऽन्योघाः।
इंद्रे। सोमः। सहः। इन्वन्। मदाय। हंति। रक्षः। बाधते। परि। अरातीः। वरिवः। कृण्वन्। वृजनस्य। राजा॥ १२॥ अ
ध। धारया। मध्वा। पृचानः। तिरः। रोम। पवते। अद्रिऽदुग्धः। इंदुः। इंद्रस्य। सख्यं। जुषाणः। देवः। देवस्य। मत्सरः।
मदाय। अभि। प्रियाणि। पवते। पुनानः। देवः। देवान्। स्वेन। रसेन। पृंचन्। इंदुः। धर्माणि। ऋतुऽथा। वसानः। रामोहरिः
दश। क्षिपः। अव्यत। सानौ। अव्ये। वृषा। शोणः। अभिऽकनिक्रदत्। गाः। नदयन्। एति। पृथिवीं। उत। द्यां। इंद्र ४५

© Dharmartha Trust J&K. Digitized by eGangotri

स्यऽइव। वग्नुः। आ। शृण्वे। आजौ। प्रऽचेतयन्। अर्षति। वाचं। आ। इमां। रसाय्यः। पयसा। पिन्वमानः। ईरयन्। ए मा।
षि। मधुऽमंतं। अंशुं। पवमानः। संऽतनिं। एषि। कृण्वन्। इंद्राय। सोम। परिऽसिच्यमानः। एव। पवस्व। मदिरः।
मदाय। उदऽग्राभस्य। नमयन्। वधऽस्नैः। परि। वर्णं। भरमाणः। रुशंतं। गव्युः। नः। अर्ष। परि। सोम। सिक्तः।
।३। आ। जुष्टी। नः। इंदो इति। सुऽपथा। सुऽगानि। उरौ। पवस्व। वरिवांसि। कृण्वन्। घनाऽइव। विष्वक्। दुःऽइता
नि। विऽघ्नन्। अधि। स्नुना। धन्व। सानौ। अव्ये। वृष्टिं। नः। अर्ष। दिव्यां। जिगत्नुं। इळाऽवतीं। शंऽगयीं। जीरऽ
दानुं। स्तुकाऽइव। वीता। धन्व। विऽचिन्वन्। बंधून्। इमान्। अवरान्। इंदो इति। वायून्। ग्रंथिं। न। वि। स्य।
ग्रथितं। पुनानः। ऋजुं। च। गातुं। वृजिनं। च। सोम। अत्यः। न। क्रदः। हरिः। आ। सृजानः। मर्यः। देव। धन्व।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ १ सत्यंऽयाना। अनुष्टः। मदाय। देवऽतातिं। इंदो इति। परि। स्नुना। धन्व। सानौ। अव्ये। सहस्रऽधारः। सुरभिः। अद

५८ ब्धः। परि। स्रव। वाजऽसातौ। नृऽसह्ये। अरऽरमानः। ये। अरथाः। अयुक्ताः। अत्यासः। न। सस्रुजानाः। सः। आजौ।

एते। शुक्रासः। धन्वंति। सोमाः। देवासः। तान्। उप। याता। पिबध्यै॥ ३४॥ एव। नः। इंदो इति। अभि। देवऽवीतिं।

46 परि। स्रव। नभः। अर्णः। चमूषु। सोमः। अस्मभ्यं। काम्यं। बृहंतं। रयिं। ददातु। वीरऽवंतं। उग्रं। तक्षत्। यदि।

मनसः। वेनतः। वाक्। ज्येष्ठस्य। वा। धर्मणि। क्षोः। अनीके। आत्। ईं। आ। यन्। वरं। आ। वावशानाः। जुष्टं।

पतिं। कलशे। गावः। इंदुं॥ प्र। दानुऽदः। दिव्यः। दानुऽपिन्वः। ऋतं। ऋताय। पवते। सुऽमेधाः। धर्मा। भुवत्। शिव॥

वृजन्यस्य। राजा। प्र। रश्मिऽभिः। दशऽभिः। भारि। भूम॥ पवित्रेभिः। पवमानः। नृऽचक्षाः। राजा। देवानां। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

उत। मर्त्यो। नो। द्युता। भुरन्ता। रयिऽपतिः। रयीणां। अत्। अं। भरत्। असुऽअक्तं। चारु। इंदुः। अर्वान्। इव। श्रवसे। सा
तिं। अच्छ। इंद्रस्य। वायोः। अभि। वीतिं। अर्ष। सः। नः। सहस्रा। बृहतीः। इषः। दाः। भव। सोम। द्रविणःऽवि
त्। पुनानः। ५५। देवऽअव्यः। नः। परिऽसिच्यमानाः। क्षयं। सुऽवीरं। धन्वंतु। सोमाः। आऽयुज्यवः। सुऽम
ना। तिं। विश्वऽवाराः। होतारः। दिविऽयजः। मंद्रऽतमाः। एव। देव। देवऽताता। पवस्व। महे। सोम। प्सरसे। देवऽपानः।
महः। चित्। हि। स्मसि। हिताः। सऽमर्ये। कृधि। सुस्थाने इति सुऽस्थाने। रोदसी इति। पुनानः। अश्वः। न। क्र
दः। वृषऽभिः। युजानः। सिंहः। न। भीमः। मनसः। जवीयान्। अर्वाचीनैः। पथिऽभिः। ये। रजिष्ठाः। आ। पव
स्व। सौमनसं। नः। इंदो इति। शतं। धाराः। देवऽजाताः। असृग्रन्। सहस्रं। एनाः। कवयः। मृजंति। इंदो इति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ सनित्रं। दिवः। आ। पवस्व। परिऽएता। असि। महतः। धनस्य। दिवः। न। सर्गाः। असस्रग्रं। अन्हां। राजा। न।
८० मित्रं। प्र। मिनाति। धीरः। पितुः। न। पुत्रः। क्रतुऽभिः। यतानः। आ। पवस्व। विशे। अस्यै। अजीतिं। ३८। प्र। ते।
47 धाराः। मधुऽमतीः। असृग्रन्। वारान्। यत्। पूतः। अतिऽएषि। अव्यान्। पवमान। पवसे। धाम। गोनां।
जज्ञानः। सूर्यं। अपिन्वः। अर्कैः। कनिक्रदत्। अनु। पथ्यां। ऋतस्य। शुक्रः। वि। भासि। अमृतस्य। धाम।
सः। इंद्राय। पवसे। मत्सरऽवान्। हिन्वानः। वाचं। मतिऽभिः। कवीनां। दिव्यः। सुऽपर्णः। अव। चक्षि। सोम।
पिन्वन्। धाराः। कर्मणा। देवऽवीतौ। आ। इंदो इति। विश। कलशं। सोमऽधानं। क्रंदन्। इहि। सूर्यस्य। उप। रामः
रश्मिं। तिस्रः। वाचः। ईरयति। प्र। वह्निः। ऋतस्य। धीतिं। ब्रह्मणः। मनीषां। गावः। यंति। गोऽपतिं। पृछमा

© Dharmartha Trust J&K. Digitized by eGangotri

नाः। सोमं। यंति। मतयः। वावशानाः। सोमं। गावः। धेनवः। वावशानाः। सोमं। विप्राः। मतिऽभिः। पृच्छमा
नाः। सोमः। सुतः। पूयते। अज्यमानः। सोमे। अर्काः। त्रिऽस्तुभः। सं। नवंते॥ ३०॥ एव। नः। सोम। परिऽसि
च्यमानः। आ। पवस्व। पूयमानः। स्वस्ति। इंद्रं। आ। विश। बृहता। रवेण। वर्धय। वाचं। जनय। पुरंऽधिं। आ।
जागृविः। विप्रः। ऋता। मतीनां। सोमः। पुनानः। असदत्। चमूषु। सपंति। यं। मिथुनासः। निऽकामाः। अ
ध्वर्यवः। रथिरासः। सुऽहस्ताः। सः। पुनानः। उप। सूरे। न। धाता। आ। उभे इति। अप्राः। रोदसी इति। वि।
सः। आवः। ऋत्या। वः। प्रिया। चित्। यस्य। प्रियसासः। ऊती। सः। तु। धनं। कारिणे। न। प्र। यंसत्। सः। वर्द्धि
ता। वर्द्धनः। पूयमानः। सोमः। मीढ्वान्। अभि। नः। ज्योतिषा। आवीत्। स्वःऽविदः। अभि। गाः। अद्रिं।

येनानः पूर्वे पितरः पदज्ञाः

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. उत्सन्। अक्रान्। समुद्रः। प्रथमे। विधर्मन्। जनयन्। प्रजाः। भुवनस्य। राजा। वृषा। पवित्रे। अधि। सानौ।
४८ अव्ये। बृहत्। सोमः। ववृधे। सुवानः। इंदुः॥ १८॥ महत्। तत्। सोमः। महिषः। चकार। अपां। यत्। गर्भः। अवृ
48 णीत। देवान्। अदधात्। इंद्रे। पवमानः। ओजः। अजनयत्। सूर्ये। ज्योतिः। इंदुः॥ मत्सि। वायुं। इष्टये। राधसे।
च। मत्सि। मित्रावरुणा। पूयमानः। मत्सि। शर्धः। मारुतं। मत्सि। देवान्। मत्सि। द्यावापृथिवी इति। देव। सो
म। ऋजुः। पवस्व। वृजिनस्य। हंता। अप। अमीवां। बाधमानः। मृधः। च। अभि। श्रीणन्। पयः। पयसा। अभि।
गोनां। इंद्रस्य। त्वं। तव। वयं। सखायः। मध्वः। सूदं। पवस्व। वस्वः। उत्सं। वीरं। च। नः। आ। पवस्व। भगं। च। स्वर्द
स्व। इंद्राय। पवमानः। इंदो इति। रयिं। च। नः। आ। पवस्व। समुद्रात्। सोमः। सुनः। धारया। अत्यः। न। हित्वा। सिंधुः ४८

© Dharmartha Trust J&K. Digitized by eGangotri

न। निम्नं। अभि। वाजी। अर्षा। इति। आ। योनिं। वन्यं। असदत्। पुनानः। सं। इंदुः। गोभिः। असरत्। सं। अद्भिः।
॥३॥ एषः। स्यः। ते। पवते। इंद्र। सोमः। चमूषु। धीरः। उशते। तवस्वान्। स्वःऽचक्षाः। रथिरः। सत्यऽशुष्मः। का
मः। न। यः। देवऽयतां। असर्जि। एषः। प्रत्नेन। वयसा। पुनानः। तिरः। वर्पांसि। दुहितुः। दधानः। वसानः। शर्म।
त्रिऽवरूथं। अप्ऽसु। होताऽइव। याति। समनेषु। रेभन्। नु। नः। त्वं। रथिरः। देव। सोम। परि। स्रव। चम्वोः। पूयमा
नः। अप्ऽसु। स्वादिष्ठः। मधुऽमान्। ऋतऽवा। देवः। न। यः। सविता। सत्यऽमन्मा। अभि। वायुं। वीती। अर्ष। गृणानः।
अभि। मित्रावरुणा। पूयमानः। अभि। नरं। धीऽजवनं। रथेऽस्थां। अभि। इंद्रं। वृषणं। वज्रऽबाहुं। अभि। वस्त्रा। सु
ऽवसनानि। अर्ष। अभि। धेनूः। सुऽदुघाः। पूयमानः। अभि। चंद्रा। भर्तवे। नः। हिरण्या। अभि। अश्वान्। रथिनः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ देवा। सोम॥ २०॥ अभि। नः। अर्ष। दिव्या। वसूनि। अभि। विश्वा। पार्थिवा। पूयमानः। अभि। येन। द्रविणं। अश्न
४९ वाम। अभि। आर्षेयं। जमदग्निऽवत्। नः। अया। पवा। पवस्व। एना। वसूनि। मांश्चत्वे। इंदो इति। सरसि। प्र
धन्व। ब्रध्नः। चित्। अत्र। वातः। न। जूतः। पुरुऽमेधः। चित्। तकवे। नरं। दात्। उत। नः। एना। पवया। पवस्व। अधि।
49 श्रुते। श्रवाय्यस्य। तीर्थे। षष्टिं। सहस्रा। नैगुतः। वसूनि। वृक्षं। न। पक्वं। धूनवत्। रणाय। महि। इमे। अस्य। वृषना इति।
इति मा। भूर्षे। मांश्चत्वे। वा। पृश्ने। वा। वधत्रे इति। अस्वापयत्। निऽगुतः। स्नेहयत्। च। अप। अमित्रान्। अप। अचि
तः। अच। इतः। सत्रा। पवित्रा। विऽतता। नि। एषि। अनु। एकं। धाव। सि। पूयमानः। असि। भगः। असि। दात्रस्य। शिव
दाता। असि। मघऽवा। मघवत्ऽभ्यः। इंदो इति॥ २१॥ एषः। विश्वऽवित्। पवते। मनीषी। सोमः। विश्वस्य। भुवन ४९

© Dharmartha Trust J&K. Digitized by eGangotri

स्या। राजा। द्रप्सान्। ईरयन्। विदथेषु। इंदुः। वि। वारं। अव्यं। समया। अति। याति। इंदुं। रिहंति। महिषाः। अदब्धाः।
पदे। रेभंति। कवयः। न। गृध्राः। हिन्वंति। धीराः। दशऽभिः। क्षिपाभिः। सं। अंजते। रूपं। अपां। रसेन। त्वया। वयं।
तन्नो मि॰ मो॰ पवमानेन। सोम। भरे। कृतं। वि। चिनुयाम। शश्वत्। ॥२॥ अभि। नः। वाजऽसातमं। रयिं। अर्ष। पुरुऽस्पृहं। इं
दो इति। सहस्रऽभर्णसं। तुविऽद्युम्नं। विभ्वऽसहं। परि। स्यः। सुवानः। अव्ययं। रथे। न। वर्म। अव्यत। इंदुः। अभि।
२ परि ष्य सुवानो द्रुणा। हितः। हियानः। धाराभिः। अक्षारिति। अक्षाः। इति। इंदुः। अव्यः। मदऽच्युतः। धारा। यः। ऊर्ध्वः। अध्वरे।
स्राजा। न। एति। गव्यऽयुः। सः। हि। त्वं। देव। शश्वते। वसु। मर्ताय। दाशुषे। इंदो इति। सहस्रिणं। रयिं। शतऽआ
त्मानं। विवाससि। वसो इति। वस्वः। पुरुऽस्पृहः। नि। नेदिष्ठतमाः। इषः। स्याम। सुम्नस्य। अध्रिगो

वयं ते अस्य वृत्रह

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. इत्यंघ्रिऽगो। द्युः। यां। वं। चा। स्वऽयशसं। स्वसारः। अद्रिऽसंहतं। ० प्रऽस्ना। प। यंति। कुर्मिणं॥ २७॥ आ। पारि। स्यो। हर्यतं।
५० हरिं। बभ्रुं। पुनंति। वारेण। यः। देवान्। विश्वान्। इत्। परि। मदेन। सह। गच्छति। अस्य। वः। हि। अवसा। पांतः।
दक्षऽसाधनं। यः। सूरिषु। श्रवः। बृहत्। दधे। स्वः। न। हर्यतः। सः। यो। यज्ञेषु। मानवी इति। इंदुः। जनिष्ठ। रोदसी
इति। देवः। देवी इति। गिरिऽस्थाः। अस्त्रेधन्। तं। तुविऽस्वनि। ० दक्ष्। घ्रो। परि। सिच्यसे। नरे। चा। दक्षिणाऽवते। इंद्रीयसोम पातये
देवाय। सदनऽसदे। ते। प्रत्नासः। विऽउष्टिषु। सोमाः। पवित्रे। अक्षरन्। अप। प्रोथंतः। सनुतः। हुरःऽचितः। प्रात
रिति। ता। न। अप्रऽचेतसः। तं। सखायः। पुरःऽरुचं। यूयं। वयं। च। सूरयः। अश्याम। वाजऽगंध्यं। सनेम। वाजऽप
स्त्यं॥ २८॥ आ। हर्यताय। धृष्णवे। धनुः। तन्वंति। पौंस्यं। शुक्रां। वयंति। असुराय। निःऽनिजं। विपां। अग्रे। रामशिव ५०

© Dharmartha Trust J&K. Digitized by eGangotri

महीयुवः। अधा। स्वपा। परिऽस्रुतः। वाजाः। नृ। अभि। प्र। गा। हते। यदि। विवस्वतः। धियः। हरिं। हिन्वंति। यातवे। तं। अस्य।
मर्जयामसि। मदः। यः। इंद्रऽपातमः। यं। गावः। आसऽभिः। दधुः। पुरा। नूनं। च। स्तरयः। तं। गाथया। पुराण्या। पुनानं।
अभि। अनूषत। उतो इति। कृपंत। धीतयः। देवानां। नाम। बिभ्रतीः। तं। उक्षमाणं। अव्यये। वारे। पुनंति। धर्णसिं। दूतं।
न। पूर्वऽचित्तये। आ। शासते। मनीषिणः। ॥२५॥ सः। पुनानः। मदिन्ऽतमः। सोमः। चमूषु। सीदति। पशौ। न। रेतः। आ
ऽदधत्। पतिः। वचस्यते। धियः। सः। मृज्यते। सुकर्मऽभिः। देवः। देवेभ्यः। सुतः। विदे। यत्। आसु। संऽददिः। महीः। अ
पः। वि। गाहते। सुतः। इंदो इति। पवित्रे। आ। नृऽभिः। युतः। वि। नीयसे। इंद्राय। मत्सरिन्ऽतमः। चमूषु। आ। नि। सीद

ऋ॰प॰दि॰द्र॰स्तु॰का
ह॰ १

सि। ॥२६॥ अभि। नवंते। अद्रुहः। वस्सं। न। पूर्वे। आयुनि। जातं। रिहंति। मातरः। पुनानः। इंदो इति। आ। भर। सोम।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स द्विबर्हसं।रयिं।त्वं।वस्त्र।नि।पुष्यसि।विश्वानि।दाशुषः।गृहे।त्वं।धियं।मनः।युजं।सृजा।वृष्टिं।न।तन्यतुः।
५१ त्वं।वस्त्र।नि।पार्थिवा।दिव्या।च।सोम।पुष्यसि।परि।ने।जिग्युषः।यथा।धारा।सुतस्य।धावति।रंहमाणा।
वि।अव्ययं।वारं।वाजीऽइव।सानसिः।क्रत्वे।दक्षाय।नः।कवे।पवस्व।सोम।धारया।इंद्राय।पातवे।सुतः।
मित्राय।वरुणाय।च।॥२॥पवस्व।वाजऽसातमः।पवित्रे।धारया।सुतः।इंद्राय।सोम।विष्णवे।देवेभ्यः।म
धुमत्ऽतमः।त्वां।रिहंति।मातरः।हरिं।पवित्रे।अद्रुहः।वत्सं।जातं।न।धेनवः।पवमान।विऽधर्मणि।पवमा
न।महि।श्रवः।चित्रेभिः।यासि।रश्मिऽभिः।शर्धन्।तमांसि।जिघ्नसे।विश्वानि।दाशुषः।गृहे।त्वं।द्यां।च।म रामःरामो
हिऽव्रता।पृथिवीं।च।अति।जभ्रिषे।प्रति।द्रापिं।अमुंचथाः।पवमान।महिऽत्वना॥३॥सप्तमाष्टके चतुर्थोध्यायः॥५१

© Dharmartha Trust J&K. Digitized by eGangotri

॥ ॐ म ॥ पुरोजितीं षोळशांधीगुः श्यावाश्विर्ययातिर्नाहुषो नहुषो मानवो मनुः सांवरण इति त्र्यचाः शे
षः प्रजापतिर्वाच्यो गायत्र्यौ क्राणाष्टौ त्रित औष्णिहं वै प्र पुनानाय षड्द्वित आप्त्यः सखायः पर्वतनार
दौ काश्यपौ द्वे शिखंडिन्यौ वाप्सरसौ तं वः इंद्रमच्छ चक्षुर्नाग्निश्चाक्षुषश्चक्षुर्मानवो मनुराप्सव इति
त्र्यचाः पंचाग्निः परीतः षड्विंशतिः सप्तऋषयः प्रागाथं तृतीयाद्योकश्यौ द्विपदे अष्टम्याद्ये बृहत्यौ यव च
त स्वषोकश गौरिवीतिर्द्वे चं शक्तिरेकामृक्रे ऋजिश्वोर्ध्वसद्मा कृतयशा ऋणंचय इत्यृषयो द्वृचास्ति
स्रः शक्तिः काकुभाः प्रगाथाः स सुन्वे गायत्री यवमध्या परा सतोबृहती परि प्र द्वे धिकाग्नयो धि
ष्ण्या ऐश्वरयो द्वैपदं पर्यू षु द्वादशा त्र्यरुणत्रसदस्यू राजानौ तिस्रोनुष्टुभः पिपीलिकमध्याः ककुर्ध्वबृह

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. स्वस्तिरत्नेश्वभिराजोयारुचात्चमनानतःपारुछेविरास्वरंनानानंचतुष्कंशिशुःपांकेहिर्यणाव
५२ स्येकादशाकश्यपोयइंद्रोश्वतुष्कंदशामंमंडलमग्नेसप्तत्रिंतःपिप्रीहीनःसूक्तएकः॥ ॥हरिःऽओंम्॥
पुरःऽजिती।वः।अंधसः।सुताय।मादयित्नवे।अप।श्वानं।श्नथिष्टन।सखायः।दीर्घऽजिह्व्यं।यः।धारया।
पावकया।परिऽप्रस्यंदते।सुतः।इंदुः।अश्वः।न।कृत्व्यः।तं।दुरोषं।अभि।नरः।सोमं।विश्वाच्या।धिया।
यज्ञं।हिन्वंति।अद्रिऽभिः।सुतासः।मधुमत्ऽतमाः।सोमाः।इंद्राय।मंदिनः।पवित्रऽवंतः।अक्षरन्।देवान्।
गच्छंतु।वः।मदाः।इंदुः।इंद्राय।पवते।इति।देवासः।अब्रुवन्।वाचः।पतिः।मखस्यते।विश्वस्य।ईशानः।ओ
जसा॥ [illegible]॥ सहस्रऽधारः।पवते।समुद्रः।वाचंऽईखयः।सोमः।पतिः।रयीणां।सखा।इंद्रस्य।दिवेऽदिवे। ५२

© Dharmartha Trust J&K. Digitized by eGangotri

अयं। पूषा। रयिः। भगः। सोमः। पुनानः। अर्षति। पतिः। विश्वस्य। भूमनः। वि। अख्यत्। रोदसी इति। उभे इति।
सं। ऊं इति। प्रियाः। अनूषत। गावः। मदाय। घृष्वयः। सोमासः। कृण्वते। पथः। पवमानासः। इंदवः। यः। ओजि
ष्ठः। तं। आ। भर। पवमान। श्रवाय्यं। यः। पंच। चर्षणीः। अभि। रयिं। येन। वनामहै। सोमाः। पवंते। इंदवः। अस्म
भ्यं। गातुवित्ऽतमाः। मित्राः। सुवानाः। अरेपसः। सुऽआध्यः। स्वःऽविदः। २। सुस्वानासः। वि। अद्रिऽभिः।
चितानाः। गोः। अधि। त्वचि। इषं। अस्मभ्यं। अभितः। सं। अस्वरन्। वसुऽविदः। ९। ते। पूताः। विपःऽचितः। सो
मासः। दधिऽआशिरः। सूर्यासः। न। दर्शतासः। जिगत्नवः। ध्रुवाः। घृते। प्र। सुन्वानस्य। अंधसः। मर्तः।
न। वृत। तत्। वचः। अप। श्वानं। अराधसं। हत। मखं। न। भृगवः। आ। जामिः। अत्के। अव्यत। भुजे। न। पु

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ त्रः।ओण्योः।सरत्।जारः।न।योषणां।वरः।न।योनिं।आऽसदं।सः।वीरः।दक्षऽसाधनः।वि।यः।तस्तंभ।रोद
५३ सीइति।हरिः।पवित्रे।अव्यत।वेधाः।न।योनिं।आऽसदं।अव्यः।वारेभिः।पवते।सोमः।गव्ये।अधि।त्वचि।क
निक्रदत्।वृषा।हरिः।इंद्रस्य।अभि।एति।निःऽकृतं।द्रा।क्राणा।शिशुः।महीनां।हिन्वन्।ऋतस्य।दीधितिं।
विश्वा।परि।प्रिया।भुवत्।अध।द्विता।उप।त्रितस्य।पाष्योः।अभक्त।यत्।गुहा।पदं।यज्ञस्य।सप्त।धामऽभिः
अध।प्रियं।त्रीणि।त्रितस्य।धारया।पृष्ठेषु।आ।ईरय।रयिं।मिमीते।अस्य।योजना।वि।सुऽक्रतुः।जज्ञानं।
सप्त।मातरः।वेधां।अशासत।श्रिये।अयं।ध्रुवः।रयीणां।चिकेत।यत्।अस्य।व्रते।सऽजोषसः।विश्वे।देवा
सः।अद्रुहः।स्पार्हाः।भवंति।रंतयः।जुषंत।यत्।४।यं।ईं।मिति।गर्भं।ऋतऽवृधः।दृशे।चारुं।अजीजनन्। ५३

© Dharmartha Trust J&K. Digitized by eGangotri

कविं। महिषं। अध्वरे। पुरः। स्पृहं। समीचीने इति सं। ईचीने। अभि। त्मना। यह्वी इति। ऋतस्य। मातरा। तन्वाना। य
ज्ञं। आनुषक्। यत्। अंजते। ऋत्वा। शुक्रेभिः। अक्षऽभिः। ऋणोः। अप। व्रजं। दिवः। हिन्वन्। ऋतस्य। दीधितिं। प्र। अध्व
रा। प्र। पुनानाय। वेधसे। सोमाय। वचः। उत्ऽयतं। भृतिं। न। भर। मतिऽभिः। जुजोषते। परि। वाराणि। अव्यया।
गोभिः। अंजानः। अर्षति। त्री। सधऽस्था। पुनानः। कृणुते। हरिः। परि। कोशं। मधुऽश्चुतं। अव्यये। वारे। अर्षति।
पु तीनां। अभि। वाणीः। ऋषीणां। सप्त। नूषत। परि। नेता। विश्वऽदेवः। अदाभ्यः। सोमः। पुनानः। चम्वोः। विशत्। हरिः।
परि। दैवीः। अनु। स्वधाः। इंद्रेण। याहि। सऽरथं। पुनानः। वाघत्। वाघत्ऽभिः। अमर्त्यैः। परि। सप्तिः। न। वाजऽ
युः। देवः। देवेभ्यः। सुतः। विऽआनशिः। पवमानः। वि। धावति। ४। सखायः। आ। नि। सीदत। पुनानाय। प्र। गा

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. यत।शिशुं।न।यज्ञैः।परि।भूषत।श्रिये।सं।ईं।इति।वत्सं।न।मातृऽभिः।सृजत।गयऽसाधनं।देवऽअव्यं।मदं।अ
५५ भि।द्विऽशवसं।पुनाना।दक्षऽसाधनं।यथा।शर्द्धाय।वीतये।यथा।मित्राय।वरुणाय।शंऽतमः।अस्मभ्यं।त्वा
वसुऽविदं।अभि।वाणीः।अनूषत।गोभिः।ते।वर्णं।अभि।वासयामसि।सः।नः।मदानां।पते।इंदो।इति।देवऽ
प्सराः।असि।सखाऽइव।सख्ये।गातुवित्ऽतमः।भव।सनेमि।कृधि।अस्मत्।आ।रक्षसं।कं।चित्।अत्रि
णो।अप।अदेवं।द्वयुं।अंहः।युयोधि।नः।।७।।तं।वः।सखायः।मदाय।पुनानं।अभि।गायत।०।स्वदयंत। शिशुंनयज्ञैः
गूर्तिऽभिः।सं।वत्सःऽइव।मातृऽभिः।इंदुः।हिन्वानः।अज्यते।देवऽअवीः।मदः।मतिऽभिः।परिऽकृतः।अयं।द
क्षाय।साधनः।अयं।शर्द्धाय।वीतये।अयं।देवेभ्यः।मधुमत्ऽतमः।सुतः।गोऽमत्।नः।इंदो।इति।अश्वऽ ५५

© Dharmartha Trust J&K. Digitized by eGangotri

अस्मत्।

ग्नत्।सुतः।सुऽदक्षः।धन्वा।शुचिः।तो।वर्णं।अधि।गोषु।दीधरं।सः।नः।हरीणां।पते।इंद्रो इति।देवप्सरः।तमः।सखाऽइव।सखे।नर्यः।रुचे।भव।सनेमि।त्वं।आ।अदेवं।कं।चित्।अत्रिणं।सऽका।इंद्रो इति।परि।बाधः।अप।द्वयुं॥ ८॥इंद्र।अच्छ।सुताः।इमे।वृषणं।यंतु।हरयः।श्रुष्टी।जाताः।सः।इंदवः।स्वःऽविदः॥अयं।भराय।सानसिः।इंद्राय।पवते।सुतः।सोमः।जैत्रस्य।चेतति।यथा।विदे॥ ९॥अस्मा भं।गृभ्णीत।सानसिं।वज्रं।च।वृषणं।भरत्।सं।अप्सुऽजित्।प्र।धन्वा।सोम।जागृविः।१०।इंदुः।मंतिः।शुष्मं।आ।भर।स्वःऽविदं।इंद्राय।वृषणं।मदं।पवस्व।विश्वऽदर्शतः।सुहस्त्यः।या।मा।पथिऽकृत्।विऽचक्षणः॥१॥अस्मभ्यं।गातुवित्ऽतमः।देवेभ्यः।मधुमत्ऽतमः।सहस्रं।याहि।पथिऽभिः।कनिक्रदत्।पवस्व।देवऽवीतये।इंद्रो इति।धारा भिः।ओ

इंद्रायेंदोपरिस्रु

प॰स॰ न्सा। आ। कलशं। मधुऽमान्। सोम। नः। सदः॥ त्वां। द्रप्साः। उदऽप्रुतः। [illegible] इंद्रं। मदाय। ववृधुः। त्वां। देवासः।
५५ अमृताय। कं। पपुः॥ आ। नः। सुतासः। इंदवः। पुनानाः। धावत। रयिं। वृष्टिऽद्यावः। रीतिऽआपः। स्वःऽविदः॥ सो-
मः। पुनानः। ऊर्मिणा। अव्यः। वारं। वि। धावति। अग्रे। वाचः। पवमानः। कनिक्रदत्॥३०॥ धीभिः। हिन्वंति।
वाजिनं। वने। क्रीळंतं। अतिऽअविं। अभि। त्रिऽपृष्ठं। मतयः। सं। अस्वरन्॥ असर्जि। कलशान्। अभि। मी-
ढ्वे। सप्तिः। न। वाजऽयुः। पुनानः। वाचं। जनयन्। असिस्यदत्॥ पवते। हर्यतः। हरिः। अति। ह्वरांसि। रंह्या।
अभि। अर्षन्। स्तोतृऽभ्यः। वीरऽवत्। यशः॥ अया। पवस्व। देवऽयुः। मधोः। धाराः। असृक्षत। रेभन्। पवि-
त्रं। परि। एषि। विश्वतः॥३१॥ परि। इतः। सिंचत। सुतं। सोमः। यः। उत्ऽतमं। हविः। दधन्वान्। यः। नर्यः। अप्ऽ ५५

© Dharmartha Trust J&K. Digitized by eGangotri

सु । अंतः । आ । सुसाव । सोमं । अद्रिऽभिः । नूनं । पुनानः । अविऽभिः । परि । स्रव । अदब्धः । सु
रभिंऽतरः । सुते । चित् । त्वा । अप्ऽसु । मदामः । अंधसा । श्रीणंतः । गोभिः । उत्ऽतरं । परि । सु
वानः । चक्षसे । देवऽमादनः । क्रतुः । इंदुः । विऽचक्षणः । पुनानः । सोम । धारया । अपः । वसानः ।
अर्षसि । आ । रत्नऽधाः । योनिं । ऋतस्य । सीदसि । उत्सः । देवः । हिरण्ययः । दुहानः । ऊधः ।
दिव्यं । मधु । प्रियं । प्रत्नं । सधऽस्थं । आ । असदत् । आऽपृच्छ्यं । धरुणं । वाजी । अर्षति । नृऽ
भिः । धूतः । विऽचक्षणः ॥ ३२ ॥ पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः । त्वं । विप्रः ।
अभवः । अंगिरःऽतमः । मध्वा । यज्ञं । मिमिक्ष । नः । सोमः । मीढ्वान् । पवते । गातुवित्ऽतमः ।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. ऋषिः। विप्रः। विऽचक्षणः। त्वं। कविः। अभवः। देवऽवीतमः। आ। सूर्यं। रोहयः। दिवि। सोमः। ऊं इति
५६ सुवानः। सोतृऽभिः। अधि। स्नुऽभिः। अवीनां। अश्वयाऽइव। हरिता। याति। धारया। मंद्रया।
याति। धारया। अनूपे। गोऽमान्। गोभिः। अक्षाः। इति। सोमः। दुग्धाभिः। अक्षाः। इति। समु
द्रं। न। संऽवरणानि। अग्मन्। मंदी। मदाय। तोशते। आ। सोम। सुवानः। अद्रिऽभिः। तिरः। वा
राणि। अव्यया। जनः। न। पुरि। चम्वोः। विशत्। हरिः। सदः। वनेषु। दधिषे॥ ३३॥ सः। ममृजे।
तिरः। अण्वानि। मेष्यः। मीढ्हे। सप्तिऽभिः। न। वाजऽयुः। अनुऽमाद्यः। पवमानः। मनीषिऽभिः। सो
मः। विप्रेभिः। ऋक्वऽभिः। प्र। सोम। देवऽवीतये। सिंधुः। न। पिप्ये। अर्णसा। अंशोः। पयसा। ५६

© Dharmartha Trust J&K. Digitized by eGangotri

मदिरः। नृऽजा। गोभिः। अछ। कोशं। मधुऽश्चुतं। आ। हर्यतः। अर्जुने। अत्के। अव्यत। प्रियः। सूनुः।
न। मर्ज्यः। तं। ईं। हिन्वंति। अपसः। यथा। रथं। नदीषु। आ। गभस्त्योः। अभि। सोमासः। आयवः।
पवंते। मद्यं। मदं। समुद्रस्य। अधि। विष्टपि। मनीषिणः। मत्सरासः। स्वःऽविदः। तरत्। समुद्रं। प
वमानः। ऊर्मिणा। राजा। देवः। ऋतं। बृहत्। अर्षत्। मित्रस्य। वरुणस्य। धर्मणा। प्र। हिन्वानः।
ऋतं। बृहत्॥३४॥ नृऽभिः। येमानः। हर्यतः। विऽचक्षणः। राजा। देवः। समुद्रियः। इंद्राय। पवते।
मदः। सोमः। मरुत्वते। सुतः। सहस्रऽधारः। अति। अव्यं। अर्षति। तं। ईं। मृजंति। आयवः।
पुनानः। चमू इति। जनयन्। मतिं। कविः। सोमः। देवेषु। रण्यति। अपः। वसानः। परि। गोभिः।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. उत्ऽतरः। सीदन्। वनेषु। अव्यत। तदं। अहं। सोम। आररण। सख्ये। इंदो इति। दिवेऽदिवे। पुरूणि। बभ्रो इति। नि। च
५८ रंति। मां। अव। परिऽधीन्। अति। तान्। इहि। उत। अहं। नक्तं। उत। सोम। ते। दिवा। सख्याय। बभ्रो इति। ऊध व
नि। घृणा। तपंतं। अति। सूर्यं। परः। शकुनाःऽइव। पप्तिम॥५॥ मृज्यमानः। सुऽहस्त्य। समुद्रे। वाचं। इन्व
सि। रयिं। पिशंगं। बहुलं। पुरुऽस्पृहं। पवमान। अभि। अर्षसि। मृजानः। वारे। पवमानः। अव्यये। वृषा। अ
व। चक्रदः। वने। देवानां। सोम। पवमान। निःऽकृतं। गोभिः। अंजानः। अर्षसि। पवस्व। वाजऽसातये। अभि।
विश्वानि। काव्या। त्वं। समुद्रं। प्रथमः। वि। धारयः। देवेभ्यः। सोम। मत्सरः। ॰ दिव्या। च। सोम। धर्मऽभिः। त्वां।
विप्रासः। मतिऽभिः। विऽचक्षण। शुभ्रं। हिन्वंति। धीतिऽभिः। पवमानाः। असृक्षत। पवित्रं। अति। धारया। ५८

सतूपवस्वपरिपार्थिवंरजो

© Dharmartha Trust J&K. Digitized by eGangotri

अंधोवसानःपरि
नो।

मरुत्वंतः। मत्सरः। इंद्रियाः। हयाः। मेधां। अभि। प्रयांसि। च। [illegible] कोशं। अर्षति। इंदुः। हियानः। सोतृ
भिः। जनयन्। ज्योतिः। मंदनाः। अवीवशत्। गाः। कृण्वानः। न। निःऽनिजं।२। पवस्व। मधुमत्ऽतमः। इंद्राय। सो
म। क्रतुवित्ऽतमः। मदः। महि। द्युक्षऽतमः। मदः। यस्य। ते। पीत्वा। वृषभः। वृषऽयते। अस्य। पीता। स्वःऽविदः। सः। सु
प्रकेतः। अभि। अक्रमीत्। इषः। अच्छ। वाजं। न। एतशः। त्वं। हि। अंग। दैव्या। पवमान। जनिमानि। द्युमत्ऽतमः। अ
मृतऽत्वाय। घोषयः। येन। नवऽग्वः। दध्यङ्। अपऽऊर्णुते। येन। विप्रासः। आपिरे। देवानां। सुम्ने। अमृतस्य। चारु
णः। येन। श्रवांसि। आनशुः। एषः। स्यः। धारया। सुतः। अव्यः। वारेभिः। पवते। मदिन्ऽतमः। क्रीडन्। ऊर्मिभिः। अ
पांऽइव।३। यः। उस्रियाः। अप्याः। अंतः। अश्मनः। निः। गाः। अकृंतत्। ओजसा। अभि। व्रजं। तत्निषे। गव्यं।

© Dharmartha Trust J&K. Digitized by eGangotri

१·स· अश्व्यं।वर्मीऽइव।धृष्णो इति।आ।रुज।आ।सोत।परि।सिंचत।अश्वं।न।स्तोमं।अप्ऽतुरं।रजःऽतुरं।वनऽक्रक्षं।उ
५८ दऽप्रुतं।सहस्रऽधारं।वृषभं।पयःऽवृधं।प्रियं।देवाय।जन्मने।ऋतेन।यः।ऋतऽजातः।विऽववृधे।राजा।देवः।ऋ
58 तं।बृहत्।अभि।द्युम्नं।बृहत्।यशः।इषः।पते।दिदीहि।देव।देवऽयुः।वि।कोशं।मध्यमं।युव।आ।वच्यस्व।सुऽद
क्ष।चम्वोः।सुतः।विशां।वह्निः।न।विश्पतिः।वृष्टिं।दिवः।पवस्व।रीतिं।अपां।जिन्व।गोऽइष्टये।धियः।११।एतं।
ऊं इति।त्यं।मदऽच्युतं।सहस्रऽधारं।वृषभं।दिवः।दुहुः।विश्वा।वसूनि।बिभ्रतं।वृषा।वि।जज्ञे।जनयन्।अमर्त्यः।
प्रऽतपन्।ज्योतिषा।तमः।सः।सुऽस्तुतः।कविऽभिः।निःऽनिजं।दधे।त्रिऽधातु।अस्य।दंससा।सः।सुन्वे।यः।
वसूनां।यः।रायां।आऽनेता।यः।इळानां।सोमः।यः।सुऽक्षितीनां।यस्य।नः।इन्द्रः।पिबात्।यस्य।मरुतः।यस्य। ५८

© Dharmartha Trust J&K. Digitized by eGangotri

वा । अर्यमणा । भगः । आ । येन । मित्रावरुणा । करामहे । आ । इंद्रं । अवसे । महे । इंद्राय । सोम । पातवे । नृऽभिः । यतः । सुऽ
आयुधः । मदिन्ऽतमः । पवस्व । मधुमत्ऽतमः । इंद्रस्य । हार्दि । सोमऽधानं । आ । विश । समुद्रंऽइव । सिंधवः । जुष्टः ।
मित्राय । वरुणाय । वायवे । दिवः । विष्टंभः । उत्ऽतमः ॥ ३१ ॥ परि । प्र । धन्व । इंद्राय । सोम । स्वादुः । मित्राय । पूष्णे । भ
गाय । इंद्रः । ते । सोम । सुतस्य । पेयाः । क्रत्वे । दक्षाय । विश्वे । च । देवाः । एव । अमृताय । महे । क्षयाय । सः । शुक्रः । अर्ष ।
दिव्यः । पीयूषः । पवस्व । सोम । महान् । समुद्रः । पिता । देवानां । विश्वा । अभि । धाम । शुक्रः । पवस्व । देवेभ्यः । सोम ।
दिवे । पृथिव्यै । शं । च । प्रऽजायै । दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । विऽधर्मन् । वाजी । पवस्व । पवस्व । सो
म । द्युम्नी । सुऽधारः । महां । अवीनां । अनु । पूर्व्यः । नृऽभिः । येमानः । जज्ञानः । पूतः । क्षरत् । विश्वानि । मंद्रः । स्वःऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ वित्ता।इंदुः।पुनानः।प्रऽअं।पुराणः।कर्त्ता।विश्वानि।द्रविणानि।नः।पवस्व।सोम।क्रत्वे।दक्षाय।अश्वः।न।निक्तः।
५९ वाजी।धनाय।।२०।।तं।तं।[illegible] सोतारः।रसं।मदाय।पुनंति।सोमं।महे।द्युम्नाय।शिशुं।जज्ञानं।हरिं।मृजं
ति।पवित्रे।सोमं।देवेभ्यः।इंदुं।इंदुः।पविष्ट।चारुः।मदाय।अपां।उपऽस्थे।कविः।भगाय।बिभर्त्ति।चारु।इंद्रस्य।ना
59 मा।येन।विश्वानि।वृत्रा।जघान।पिबंति।अस्य।विश्वे।देवासः।गोभिः।श्रीतस्य।नृऽभिः।सुतस्य।प्र।सुवानः।
अक्षारिति।सहस्रऽधारः।तिरः।पवित्रं।वि।वारं।अव्यं।[illegible]।स्वः।वाजी।अक्षारिति।सहस्रऽरेताः।अत्ऽभिः।मृ
जानः।गोभिः।श्रीणानः।प्र।सोम।याहि।इंद्रस्य।कुक्षा।नृऽभिः।येमानः।अद्रिऽभिः।सुतः।असर्जि।वाजी।ति
रः।पवित्रं।इंद्राय।सोमः।सहस्रऽधारः।अंजंति।एनं।मध्वः।इंद्राय।वृष्णे।इंदुं।मदाय।देवेभ्यः।स्वा।रथा।पा ५९

रत्नो।

© Dharmartha Trust J&K. Digitized by eGangotri

ऽसे। अपः। वसानेः। हरिः। मृजे। ति। इंदुः। इंद्राय। नो। शते। अमि। लो। रा। ते। श्रीणन्। गुभ्रः। रिणन्। अपुः। र ऽ। आ। परि। ऊं। इ

सू तिऽप्र। धन्व। वाजऽसातये। परि। वृत्राणि। सक्षणिः। द्विषः। तरध्यै। ऋणऽयाः। नः। ईयसे। अनु। हि। त्वा। सुतं। सोम।

मदामसि। महे। सऽमर्यऽराज्ये। वाजान्। अभि। पवमान। प्र। गाहसे। अजीजनः। पवमान। सूर्यं। विऽधारे। शक्म हि

ना। पयः। गोऽजीरया। रंहमाणः। पुरंऽध्या। अजीजनः। अमृत। मर्त्येषु। आ। ऋतस्य। धर्मन्। अमृतस्य। चा

रुणः। सदा। असरः। वाजं। अच्छ। सनिष्यदत्। अभि। अभि। हि। श्रवसा। ततर्दिथ। उत्सं। न। कं। चित्। जनऽ

पानं। अक्षितं। [illegible] शर्याभिः। न। भरमाणः। गभस्त्योः। आ। इंदुः। के। चित्। पश्यमाना। स्वः। आ। प्वे। वसुऽरु

चः। दिव्याः। अभि। अनूषत। वारेण। देवः। सविता। वि। ऊर्णुते। रसा। स्वेऽइति। सोमा। प्रथमाः। रक्ताः। बर्हिषः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ महा। वाजाय। अव॑से। धियं। दुधुः। सः। त्वं। नः। जीर। वीर्यो॑य। चोदय। दिवः। पीयूषं। पूर्व्यं। यत्। उक्थ्यं। महः। गा

६०. हात्। दिवः। आ। निः। अधुक्षत। इंद्रं। अभि। जायमानं। सं। अस्वरन्। अध। यत्। इमे इति। पवमान। रोदसी इति। इ

मा। च। विश्वा। भुवना। अभि। मज्मना। यूथे। न। निःऽस्थाः। वृषभः। वि। तिष्ठसे। सोमः। पुनानः। अव्यये। वारे। शि

शुः। न। क्रीळन्। पवमानः। अक्षाः। रिति। सहस्रऽधारः। शतऽवाजः। इंदुः। एषः। पुनानः। मधुऽमान्। ऋतऽवा। इंद्रा

न य। इंदुः। पवते। स्वादुः। ऊर्मिः। वाजऽसनिः। वरिवःऽवित्। वयःऽधाः। सः। पवस्व। सहमानः। पृतन्यून्। सेधन्। रक्षां

सि। अप। दुःऽगहानि। स्वऽआयुधः। सस्रहान्। सोम। शत्रून्। ॥ ३॥ अया। रुचा। हरिण्या। पुनानः। विश्वा। द्वे

षांसि। तरति। स्वयुग्वऽभिः। सूरः। न। स्वयुग्वऽभिः। धारा। सुतस्य। रोचते। पुनानः। अरुषः। हरिः। विश्वा। यत्। ७

© Dharmartha Trust J&K. Digitized by eGangotri

रूपा।परिऽयाति।ऋक्वऽभिः।सऽस्नुः।आस्येभिः।ऋक्वऽभिः।स्वां।यत्।पणीनां।विदः।वसु।सं।मातृऽभिः।मर्जयसि।

आ स्वे।दमे।ऋतस्य।धीतिऽभिः।दमे।पराऽवतः।न।साम।तत्।यत्।आऽरणंति।धीतयः।त्रिऽधातुऽभिः।अरुषीभिः।वयः।

दधे।रोचमानः।वयः।दधे।पूर्वी।अनु।प्रऽदिशः।याति।चेकितत्।सं।रश्मिऽभिः।यतते।दर्शतः।रथः।दैव्यः।दर्शतः।

रथः।अगमन्।उक्थानि।पौंस्या।इंद्रं।जैत्राय।हर्षयन्।वज्रः।च।यत्।भवथः।अनपऽच्युता।समत्ऽसु।अनप

ऽच्युता॥२४॥ ना।ना।नं।वै।ऊं इति।नः।धियः।वि।व्रतानि।जनानां।तक्षा।रिष्टं।रुतं।भिषक्।ब्रह्मा।सुन्वंतं।इ

इंद्रायेंदोप० छति।ॐ।जरतीभिः।ओषधीभिः।पर्णेभिः।शकुनानां।कार्मारः।अश्मऽभिः।द्युऽभिः।हिरण्यऽवंतं।इच्छति।०।का

रुः।अहं।ततः।भिषक्।उपलऽप्रक्षिणी।नना।नाना।धियः।वसुऽयवः।अनु।गाःऽइव।तस्थिम।०।अश्वः।वो

© Dharmartha Trust J&K. Digitized by eGangotri

प. स. ळ्हा। सुऽखं। रथं। हसनां। उपऽमंत्रिणः। शेपः। रोमण्ऽवंतौ। भेदौ। वाः। इत्। मंडूकः। इच्छति। ०। ४। शर्यणाऽवति। सो

६१ मं। इंद्रः। पिबतु। वृत्रऽहा। बलं। दधानः। आत्मनि। करिष्यन्। वीर्यं। महत्। ०। आ। पवस्व। दिशां। पते। आर्जीकात्। सो

मा। मीढ्वः। ऋतऽवाकेन। सत्येन। श्रद्धया। तपसा। सुतः। ०। पर्जन्यऽवृद्धं। महिषं। तं। सूर्यस्य। दुहिता। आ। अभरत्।

61 तं। गंधर्वाः। प्रति। अगृभ्णन्। तं। सोमे। रसं। आ। अदधुः। ०। ऋतं। वदन्। ऋतऽद्युम्न। सत्यं। वदन्। सत्यऽकर्मन्।

श्रद्धां। वदन्। सोम। राजन्। धात्रा। सोम। परिऽकृतः। ०। सत्यंऽउग्रस्य। बृहतः। सं। स्रवंति। संऽस्रवाः। सं। यंति। र

सिनः। रसाः। पुनानः। ब्रह्मणा। हरे। ०। ४। यत्र। ब्रह्मा। पवमान। छंदस्यां। वाचं। वदन्। ग्राव्णा। सोमे। मही

यते। सोमेन। आऽनंदं। जनयन्। ०। यत्र। ज्योतिः। अजस्रं। यस्मिन्। लोके। स्वः। हितं। तस्मिन्। मां। धेहि। पवमान। ६१

© Dharmartha Trust J&K. Digitized by eGangotri

अमृते।लोके।अक्षिते।।०।।यत्र।राजा।वैवस्वतः।यत्र।अवऽरोधनं।दिवः।यत्र।अमूः।यह्वतीः।आपः।तत्र।मां।अ
मृतं।कृधि।।०।।यत्र।अनुऽकामं।चरणं।त्रिऽनाके।त्रिऽदिवे।दिवः।लोकाः।यत्र।ज्योतिष्मंतः।।०।।यत्र।कामाः।नि
ऽकामाः।च।यत्र।ब्रध्नस्य।विष्टपं।स्वधा।च।यत्र।तृप्तिः।च।।०।।यत्र।आऽनंदाः।च।मोदाः।च।मुदः।प्रऽमुदः।
आसते।कामस्य।यत्र।आप्ताः।कामाः।।०।।२०।।यः।इंदोः।पवमानस्य।अनु।धामानि।अक्रमीत्।तं।आहुः।
सुऽप्रजाः।इति।यः।ते।सोम।अविधत्।मनः।।०।।ऋषे।मंत्रऽकृतां।स्तोमैः।कश्यप।उत्ऽवर्धयन्।गिरः।सोमं।न
मस्य।राजानं।यः।जज्ञे।वीरुधां।पतिः।।०।।सप्त।दिशः।नानाऽसूर्याः।सप्त।होतारः।ऋत्विजः।देवाः।आदित्याः।
ये।सप्त।तेभिः।सोम।अभि।रक्ष।नः।।०।।यत्।ते।राजन्।शृतं।हविः।तेन।सोम।अभि।रक्ष।नः।अरातिऽवा।मा।

© Dharmartha Trust J&K. Digitized by eGangotri

१. स. नः। तारीत्। सोम इति। चा। नः। किं। चन। आ। मम। मत्। ।७। ॥२८॥ इति नवमं मंडलं ॥ अग्ने। बृहन्। उषसां। ऊर्ध्वः। अस्थात्।

६२ निःऽजगन्वान्। तमसः। ज्योतिषा। आ। अगात्। अग्निः। भानुना। रुशता। सुऽअंगः। आ। जातः। विश्वा। सद्मा-

नि। अप्राः। सः। जातः। गर्भः। असि। रोदस्योः। अग्ने। चारुः। विऽभृतः। ओषधीषु। चित्रः। शिशुः। परि। तमांसि।

अक्तून्। प्र। मातृऽभ्यः। अधि। कनिक्रदत्। गाः। विष्णुः। इत्था। परमं। अस्य। विद्वान्। जातः। बृहन्। अभि। पाति।

तृतीयं। आसा। यत्। अस्य। पयः। अक्रत। स्वं। सऽचेतसः। अभि। अर्चन्ति। अत्र। अतः। ऊं इति। जाः। पितुःऽभृतः।

जनित्रीः। अन्नऽवृधं। प्रति। चरंति। अन्नैः। ताः। ईं। प्रति। एषि। पुनः। अन्यऽरूपाः। असि। त्वं। विक्षु। मानुषीषु।

होता। होतारं। चित्रऽरथं। अध्वरस्य। यज्ञस्यऽयज्ञस्य। केतुं। रुशंतं। प्रतिऽअर्धिं। देवस्यऽदेवस्य। मह्ना। श्रि ६२

© Dharmartha Trust J&K. Digitized by eGangotri

वेषिहोत्रमुतपोत्रं

या। तु। अग्निं। अतिथिं। जनानां। सः। तु। वस्त्राणि। अध। पेशनानि। वसानः। अग्निः। नाभा। पृथिव्याः। अरुषः। आ। नः।
पदे। इळायाः। पुरःऽहितः। राजन्। यक्षि। इह। देवान्। आ। हि। द्यावापृथिवी इति। अग्ने। उभे इति। सदा। पुत्रं। न। मातरा।
ततंथ। प्र। याहि। अच्छ। उशतः। यविष्ठ। अथ। आ। वह। सहस्य। इह। देवान्। त्वं। विप्रः। हि। देवान्। उशतः। यविष्ठ। वि
द्वान्। ऋतून्। ऋतुऽपते। यज। इह। ये। दैव्याः। ऋत्विजः। तेभिः। अग्ने। त्वं। होतॄणां। असि। आऽयजिष्ठः। जनानां। मंधा
ता। असि। द्रविणःऽदाः। ऋतऽवा। स्वाहा। वयं। कृणवाम। हवींषि। देवः। देवान्। यजतु। अग्निः। अर्हन्। आ। देवानां। अ
पि। पंथां। अगन्म। यत्। शक्नवाम। तत्। अनुऽप्रवोळ्हुं। अग्निः। विद्वान्। सः। यजात्। सः। इत्। ऊं इति। होता। सः। अ
ध्वरान्। सः। ऋतून्। कल्पयाति। यत्। वः। वयं। प्रऽमिनाम। व्रतानि। विदुषां। देवाः। अविदुःऽतरासः। अग्निः। तत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. विश्वं। आ। पृणाति। विद्वान्। येभिः। देवान्। ऋतुऽभिः। कल्पयाति। यत्। पाकऽत्रा। मनसा। दीनऽदक्षाः। न। यज्ञस्य।
६२ मन्वते। मर्त्यासः। अग्निः। तत्। होता। क्रतुऽवित्। विऽजानन्। यजिष्ठः। देवान्। ऋतुऽशः। यजाति। विश्वेषां। हि। अ
ध्वराणां। अनीकं। चित्रं। केतुं। जनिता। त्वा। जजान। सः। आ। यजस्व। नृऽवतीः। अनु। क्षाः। स्पार्हाः। इषः। क्षुऽमतीः।
विश्वऽजन्याः। यं। त्वा। द्यावापृथिवी इति। यं। त्वा। आपः। त्वष्टा। यं। त्वा। सुऽजनिमा। जजान। पंथां। अनु। प्रऽविद्वान्।
पितृऽयानं। द्युऽमत्। अग्ने। संऽइधानः। वि। भाहि। ॥३०॥ इनः। राजन्। अरतिः। संऽइद्धः। रौद्रः। दक्षाय। सुसुऽमा
न्। अदर्शि। चिकित्। वि। भाति। भासा। बृहता। असिक्नीं। एति। रुशतीं। अपऽअजन्। कृष्णां। यत्। एनीं।
अभि। वर्पसा। भूत्। जनयन्। योषां। बृहतः। पितुः। जां। ऊर्ध्वं। भानुं। सूर्यस्य। स्तभायन्। दिवः। वसुऽभिः। ६२

© Dharmartha Trust J&K. Digitized by eGangotri

अरतिः । वि । भाति । भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारं । जारः । अभि । एति । पश्चात् । सुऽप्रकेतैः । द्युऽ
भिः । अग्निः । विऽतिष्ठन् । रुशत्ऽभिः । वर्णैः । अभि । रामं । अस्थात् ॥ अस्य । यामासः । बृहतः । न । वग्नून् । इंधानाः ।
अग्नेः । सख्युः । शिवस्य । ईड्यस्य । वृष्णः । बृहतः । सुऽआसः । भामासः । यामन् । अक्तवः । चिकित्रे । स्वभानः । न
यस्य । भामासः । पवंते । रोचमानस्य । बृहतः । सुऽदिवः । ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्ऽभिः । वर्षिष्ठेभिः । भा
नुऽभिः । नक्षति । द्यां । अस्य । शुष्मासः । ददृशानऽपवेः । जेहमानस्य । स्वनयन् । नियुत्ऽभिः । प्रत्ने
भिः । यः । रुशत्ऽभिः । देवऽतमः । विऽरेभत्ऽभिः । अरतिः । भाति । विऽभ्वा । सः । आ । वक्षि । महि । नः । आ ।
च । सत्सि । दिवः । पृथिव्योः । अरतिः । युवत्योः । अग्निः । सुऽतुकः । सुऽतुकेभिः । अश्वैः । रभस्वत्ऽभिः ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ रभस्वान्।आ।इह।गम्याः॥३॥प्र।ते।यक्षि।प्र।ते।इयर्मि।मन्म।भुवः।यथा।वंद्यः।नः।हवेषु।धन्वन्ऽइव।
६५ प्रऽपाः।असि।त्वं।अग्ने।इयक्षवे।पूरवे।प्रत्न।राजन्।यं।त्वा।जनासः।अभि।संऽचरंति।गावः।उष्णंऽइव।व्रजं।
यविष्ठ।दूतः।देवानां।असि।मर्त्यानां।अंतः।महान्।चरसि।रोचनेन।शिशुं।न।त्वा।जेन्यं।वर्धयंती।माता।
64 बिभर्ति।सचनस्यमाना।धनोः।अधि।प्रऽवता।यासि।हर्यन्।जिगीषसे।पशुःऽइव।अवऽसृष्टः।मूराः।अमूर।
न।वयं।चिकित्वः।महिऽत्वं।अग्ने।त्वं।अंग।वित्से।शये।वव्रिः।चरति।जिह्वया।अदन्।रेरिह्यते।युवतिं।विश्प
तिः।सन्।कूऽचित्।जायते।सनयासु।नव्यः।वने।तस्थौ।पलितः।धूमऽकेतुः।अस्नाताः।आपः।वृषभः।न।
प्र।वेति।सऽचेतसः।यं।प्रऽनयंत।मर्ताः।तनूत्यजाऽइव।तस्करा।वनर्गूइति।रशनाभिः।दशऽभिः।अभि। ६५

© Dharmartha Trust J&K. Digitized by eGangotri

रक्षाणोअग्ने

अधीतां।इयं।ते।अग्ने।नव्यसी।मनीषा।युक्ष्वा।रथं।न।शुचयत्ऽभिः।अंगैः।ब्रह्म।च।ते।जातऽवेदः।नमः।च।
इयं।च।गीः।सदं।इत।वर्द्धनी।भूत।०।तनयानि।तोका।रक्ष।उत।नः।तन्वः।अप्रऽयुच्छन्।३।१।एकः।समुद्रः।
धरुणः।रयीणां।अस्मत्।हृदः।भूरिऽजन्मा।वि।चष्टे।सिसक्ति।ऊधः।निण्योः।उपऽस्थे।उत्सस्य।मध्ये।निऽहि
तं।पदं।वेः।रिति।वेः।समानं।नीळं।वृषणः।वसानाः।सं।जग्मिरे।महिषाः।अर्वतीभिः।ऋतस्य।पदं।कवयः।नि।
पांति।गुहा।नामानि।दधिरे।पराणि।ऋतायिनीइत्यृतऽयिनी।मायिनीइति।सं।दधातेइति।मित्वा।शिशुं।ज
ज्ञतुः।वर्द्धयंतीइति।विश्वस्य।नाभिं।चरतः।ध्रुवस्य।कवेः।चित्।तंतुं।मनसा।विऽयंतः।ऋतस्य।हि।वर्तनयः। न
सुऽजातं।इषः।वाजाय।प्रऽदिवः।सचंते।अधीवासं।रोदसीइति।ववसानेइति।घृतैः।अन्नैः।ववृधातेइति।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ मधुर्नां। त्वम्न। स्वस्तृ॰। अरुषी॰। वाय। शाने॰। वि। हून्राम। मध्व॰। उत। जमारा। हृशो। कं। अंत॰। यु। मे। अंतरिक्षे। पु
६५ रा॰ जा॰। इछन्ना। वृ। विं। अविदत्ता। पूषणस्या। सत्ता। मर्या॰। कवय॰। तनु। क्षु॰। नासौ। एकौ। इला। अभि। अंहुर॰।
गात्रा। आयो॰। हा। त्वं। म॰। उप॰ मस्या। नी। कौ। पथां।। वि॰ सर्गो। धरुणे। पात। स्यौ। असत्रा। चा। सता। चापर मे। वि॰
ओमना। दक्षस्या। जन्मन्रा। अदिते॰। उप॰ स्थे। अग्नि॰। हान्न॰। प्रथम॰ जा॰। ऋतस्या। पूर्वै। आयुनि। वृषम॰। चु
धेनु॰।। ३।। इति सप्तमाष्टके पंचमोऽध्यायः।। ।।ॐ म।। अयं स्वस्ति प्रकेतुना नवार्चं त्रिशिरास्त्वाष्ट्र स्त्वचोंस
ऐंद्र आपो हि सिंधुद्वीपो वांबरीष आपं गायत्रं ध्यनुष्टुबंतं पंचमी वर्द्धमाना सप्तमी प्रतिष्ठौ चित्रषकूना
वैवस्वतयोर्यम यम्योः संवादः षष्ठ्यं युग्भिर्यमी मिथुनार्थं यमं प्रोवाच स तान्नवमी युग्मिरनिछन्प्रत्याच ६५

द्वेषान्वांगिहाविर्द्धीनआग्नेयंतुत्रित्रिष्टुबंतंघायायुजेपंचविवस्वान्वादित्योहाविर्धानंजगत्यंतंवरे
यिवांसंषोऽशयमोयामंषष्ठीलिंगोक्तदेवतापराश्चतिस्त्रःपित्र्यावांतिस्त्रश्चभ्यांपराअनुष्टुभोबृहत्यु
पांत्यायामायनाःपरेपंचोदीरतांषट्कूनाशांखःपित्र्यंजगत्येकादशीमैनंदमनआग्नेयंचतुरनुष्टुबंतंवष्टा
देवश्रवाहैसरण्यूदेवतेपौष्णश्चतस्त्रःसारस्वत्यस्तिस्त्रःपंचाप्योद्रप्सस्तिस्त्रंसौम्योवांत्येअनुष्टुभाउपां
त्यापुरस्ताद्बृहतीवापरंमत्स्योसंकुशिकाश्चतस्त्रोमसुदेवताःपराधात्रीवरात्रात्रीपराःपित्रमेधाएकाद
शीप्रस्तारपंक्तिर्जगत्युपांत्यांत्यानुष्टुप्प्रजापत्यावास्तानिरुक्तौ॥ ॐ म॥ अयं।सेः।यस्यां।रामं।राज्ञः।वंःऽभिः।
अग्नेः।अधंतां।जरितां।अभि।सैौ।ज्येष्ठेभिः।यः।मानुःऽभिः।कृष्णां।पारिऽएतिं।पारिऽवीतः।विमाऽवां।यः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ भानुऽभिः। विभाऽवा। विऽभाति। अग्निः। देवेभिः। ऋतऽवा। अजस्रः। आ। यः। विवाय। सख्या। सखिऽ
६६ भ्यः। अपरिऽह्वृतः। अत्यः। न। सप्तिः। ईशे। यः। विश्वस्याः। देवऽवीतेः। ईशे। विश्वऽआयुः। उषसः। विऽउ
ष्टौ। आ। यस्मिन्। मना। हवींषि। अग्नौ। अरिष्टऽरथः। स्कम्नाति। शूषैः। शूषेभिः। वृधः। जुषाणः।
अर्कैः। देवान्। अच्छ। रघुऽपत्वा। जिगाति। मन्द्रः। होता। सः। जुह्वा। यजिष्ठः। संऽमिश्लः। अग्निः। आ।
जिघर्ति। देवान्। तं। उस्रां। इन्द्रं। न। रेजमानं। अग्निं। गीःऽभिः। नमःऽभिः। आ। कृणुध्वं। आ। यं। विप्राः।
सः। मतिऽभिः। गृणन्ति। जातऽवेदसं। जुह्वं। सहानां। सं। यस्मिन्। विश्वा। वसूनि। जग्मुः। वाजे। न।
अश्वाः। सप्तिऽवन्तः। एवैः। अस्मे इति। ऊतीः। इन्द्रऽवातऽतमाः। अर्वाचीनाः। अग्ने। आ। कृणुष्व। अध। ६६

66

© Dharmartha Trust J&K. Digitized by eGangotri

यदा तेमर्तो अनु भोगमानट्

हि। अग्ने। मह्ना। निःऽसद्य। सद्यः। जज्ञानः। हव्यः। बभूथ। तं। ते। देवासः। अनु। केतं। आयन्। अध। अवर्धंत
प्रथमासः। ऊमाः॥३॥ स्वस्ति। नः। दिवः। अग्ने। पृथिव्याः। विश्वऽआयुः। धेहि। यजथाय। देव। सचेमहि। तव। द
स्म। प्रऽकेतैः। उरुष्य। नः। उरुऽभिः। देव। शंसैः॥ इमाः। अग्ने। मतयः। तुभ्यं। जाताः। गोभिः। अश्वैः। अभि। गृ
णंति। राधः। ं। वसो इति। दधानः। मतिऽभिः। सुऽजात। अग्निं। मन्ये। पितरं। अग्निं। आपिं। अग्निं। भ्रातरं।
सदं। इत्। सखायं। अग्नेः। अनीकं। बृहतः। सपर्यं। दिवि। शुक्रं। यजतं। सूर्यस्य॥ सिध्राः। अग्ने। धियः। अस्मे
इति। सनुत्रीः। यं। त्रायसे। दमे। आ। नित्यऽहोता। ऋतऽवा। सः। रोहित्ऽअश्वः। पुरुऽस्पृहः। द्युऽभिः। अस्मे। अहःऽ
भिः। वामं। अस्तु। द्युऽभिः। हितं। मित्रंऽइव। प्रऽयोगं। प्रत्नं। ऋत्विजं। अध्वरस्य। जारं। बाहुऽभ्यां। अग्निं। आय

© Dharmartha Trust J&K. Digitized by eGangotri

आँ।रोदसी।वृषभो।रोरवीति

प.स. नः।अजनंत।विक्षु।होतारं।नि।असादयंत।स्वयं।यजस्व।दिवि।देव।देवान्।किं।ते।पाकः।कृणवत्।अप्रऽचेताः।
६७ यथा।अयजः।ऋतुऽभिः।देव।देवान्।एव।यजस्व।तन्वं।सुऽजात।भव।नः।अग्ने।अविता।उत।गोपाः।भव।व
यःऽकृत्।उत।नः।वयःऽधाः।रास्व।च।नः।सुऽमहः।हव्यऽदातिं।त्रास्व।उत।नः।तन्वः।अप्रऽयुछन्।।र।।प्र।केतु
ना।बृहता।याति।अग्निः।ॐ।दिवः।चित्।अंतान्।उपऽमान्।उत्।आनट्।।अपां।उपऽस्थे।महिषः।ववर्द्ध।मुमो
द।गर्भः।वृषभः।ककुत्ऽमान्।अस्रेमा।वत्सः।शिमीऽवान्।अरावीत्।सः।देवऽताति।उत्ऽयतानि।कृण्वन्।स्वे
षु।क्षयेषु।प्रथमः।जिगाति।आ।यः।मूर्द्धानं।पित्रोः।अरब्ध।नि।अध्वरे।दधिरे।सूरः।अर्णः।अस्य।पत्मन्।
अरुषीः।अश्वऽबुध्नाः।ऋतस्य।योनौ।तन्वः।जुषंत।उषःऽउषः।हि।वसो इति।अग्रं।एषि।त्वं।यमयोः।अभवः। ६७

67

© Dharmartha Trust J&K. Digitized by eGangotri

विभाऽवा। ऋतायः। सप्तऽआद्। दधिषे। पदानि। जनयन्। मित्रं। तन्वे। स्वायै। भुवः। चक्षुः। महः। ऋतस्य। गोपाः।
भुवः। वरुणः। यत्। ऋताय। वेषि। भुवः। अपां। नपात्। जातऽवेदः। भुवः। दूतः। यस्य। हव्यं। जुजोषः॥ ५॥
भुवः। यज्ञस्य। रजसः। च। नेता। यत्र। नियुत्ऽभिः। सचसे। शिवाभिः। दिवि। मूर्द्धानं। दधिषे। स्वःऽसां। जिह्वां।
अग्ने। चकृषे। हव्यऽवाहं। अस्य। त्रितः। क्रतुना। वव्रे। अन्तः। इच्छन्। धीतिं। पितुः। एवैः। परस्य। सचस्यमानः।
पित्रोः। उपऽस्थे। जामि। ब्रुवाणः। आयुधानि। वेति। सः। पित्र्याणि। आयुधानि। विद्वान्। इन्द्रऽइषितः।
आप्त्यः। अभि। अयुध्यत्। त्रिऽशीर्षाणं। सप्तऽरश्मिं। जघन्वान्। त्वाष्ट्रस्य। चित्। निः। ससृजे। त्रि-
तः। गाः। भूरि। इत्। इन्द्रः। उत्ऽइनक्षन्तं। ओजः। अव। अभिनत्। सत्ऽपतिः। मन्यमानं। त्वाष्ट्रस्य। चि-

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ त्वा। विश्वऽरूपस्य। गोनां। आऽचक्राणः। त्रीणि। शीर्षा। परा। वर्गिति वर्क्॥ ४॥ आपः। हि। स्थ। मयःऽभुवः। ताः।
६८ नः। ऊर्जे। दधातन। महे। रणाय। चक्षसे। यः। वः। शिवऽतमः। रसः। तस्य। भाजयत। इह। नः। उशतीःऽइ
वा। मातरः। तस्मै। अरं। गमाम। वः। यस्य। क्षयाय। जिन्वथ। आपः। जनयथ। च। नः। शं। नः। देवीः। अभिष्ट
68 ये। आपः। भवंतु। पीतये। शं। योः। अभि। स्रवंतु। नः। ईशानाः। वार्याणां। क्षयंतीः। चर्षणीनां। अपः। याचा
अप्सु मे ऋक् ४ मि। भेषजं॥ ५॥ ओ इति। चित्। सरस्वायं। सरस्वान्। वरस्यां। निरः। पुरा। चित्। अर्णवं। जगन्वान्। पितुः।
नपातं। आ। दधीत। वेधाः। अपि। स। मि। प्रऽतरं। दीध्यानः। ना। तो। सरस्वा। सरस्वं। वशिऽएतन। तासऽलक्ष्मा। यत्।
विष्णुऽरूपा। भवाति। महः। पुत्रासः। असुरस्य। वीराः। दिवः। धर्तारः। उर्व्यया। परि। ख्यन्। उशंति। घ्नते। ६८

© Dharmartha Trust J&K. Digitized by eGangotri

अमृतासः । एतत् । एकस्य । चित् । त्यजसं । मर्त्यस्य । नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वं । आ । विविश्याः । न । यत् । पुरा । चकृम । कत् । ह । नूनं । ऋता । वदंतः । अनृतं । रपेम । गंधर्वः । अप्ऽसु । अप्या । च । योषा । सा । नः । नाभिः । परमं । जामि । तत् । नौ । गर्भे । नु । नौ । जनिता । दंपती इति दंऽपती । कः । देवः । त्वष्टा । सविता । विश्वऽरूपः । नकिः । अस्य । प्र । मिनंति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः । ५ । कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईं । ददर्श । कः । इह । प्र । वोचत् । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहनः । वीच्या । नॄन् । यमस्य । मा । यम्यं । कामः । अ । गन् । समाने । योनौ । सहऽशेय्याय । जायाऽइ आ । व । पत्ये । तन्वं । रिरिच्यां । वि । चित् । वृहेव । रथ्याऽइव । चक्रा । न । तिष्ठंति । न । नि । मिषंति । एते । देवानां । स्प

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ शः। इह। ये। चरंति। अन्येन। मत्। आहनः। याहि। तूयं। तेन। वि। वृह। रथ्याऽइव। चक्रा। रात्रीभिः। अस्मै। अहऽ
६९ भिः। दशस्येत्। सूर्यस्य। चक्षुः। मुहुः। उत्। मिमीयात्। दिवा। पृथिव्या। मिथुना। सबंधू इति सऽबंधू। य
मीः। यमस्य। बिभृयात्। अजामि। आ। घ। ता। गच्छान्। उत्ऽतरा। युगानि। यत्र। जामयः। कृणवन्। अजा
मि। उप। बर्बृहि। वृषभाय। बाहुं। अन्यं। इच्छस्व। सुऽभगे। पतिं। मत्। ॥७॥ किं। भ्राता। असत्। यत्। अना
थं। भवाति। किं। ऊं इति। स्वसा। यत्। निःऽऋतिः। निऽगच्छात्। कामऽमूता। बहु। एतत्। रपामि। तन्वा। मे। त
न्वं। सं। पिपृग्धि। न। वै। ऊं इति। ते। तन्वा। तन्वं। सं। पपृच्यां। पापं। आहुः। यः। स्वसारं। निऽगच्छात्। अन्ये
न। मत्। प्रऽमुदः। कल्पयस्व। न। ते। भ्राता। सुऽभगे। वष्टि। एतत्। बतः। बत। असि। यम। न। एव। ते। मनः। ६९

© Dharmartha Trust J&K. Digitized by eGangotri

पॅरिष्व जातेलिबुजेयवस्रं

हृदयं। च। अविदाम। अन्या। किल। त्वां। कक्ष्याऽइव। युक्तं। परि। स्वजाते। लिबुजाऽइव। वृक्षं। अन्यं। ऊं इति।

सु। त्वं। यमि। अन्यः। ऊं इति। त्वां। ०। तस्य। वा। त्वं। मनः। इच्छा। सः। वा। तव। अध। कृणुष्व। संऽविदं। सुऽभद्रां।

॥८॥ रण। रक्षो। दुदुहे। दोहसा। दिवः। पयांसि। यह्वः। अदितेः। अदाभ्यः। विश्वं। सः। वेद। वरुणः। यथा।

धिया। सः। यज्ञियः। यजतु। यज्ञियान्। ऋतून्। रपत्। गंधर्वीः। अप्या। च। योषणा। नदस्य। नादे। परि।

पातु। मे। मनः। इष्टस्य। मध्ये। अदितिः। नि। धातु। नः। भ्राता। नः। ज्येष्ठः। प्रथमः। वि। वोचति। सो इति।

चित्। नु। भद्रा। क्षुऽमती। यशस्वती। उषाः। उवास। मनवे। स्वःऽवती। यत्। ईं। उशंतं। उशता। अनु। क्र

तुं। अग्निं। होतारं। विदथाय। जीजनन्। आ। त्यं। द्रप्सं। विऽभ्वं। विऽचक्षणं। विः। आ। अभरत्। इषितः। श्येनः।

न धे

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ अध्वरे। यदि। विशः। वृणते। दस्मं। आर्याः। अग्निं। होतारं। अध। धीः। अजायत। सदा। असि। रण्वः। य
७० वसाऽइव। पुष्यते। होत्राभिः। अग्ने। मनुषः। सुऽअध्वरः। विप्रस्य। वा। यत्। [illegible] शशमानः।
उक्थ्यं। वाजं। ससऽवान्। उपऽयासि। भूरिऽभिः। ८। उत्। ईरय। पितरा। जारः। आ। भगं। इयक्षति। हर्य
70 तः। हृत्तः। इष्यति। विवक्ति। वह्निः। सुऽअपस्यते। मखः। तविष्यते। असुरः। वेपते। मती। [illegible] यः। ते। अग्ने।
सुऽमतिं। मर्तः। अक्षत्। सहसः। सूनो इति। अति। सः। प्र। शृण्वे। इषं। दधानः। वहमानः। अश्वैः। आ। सः।
द्युऽमान्। अमऽवान्। भूषति। द्यून्। यत्। अग्ने। एषा। संऽइतिः। भवाति। देवी। देवेषु। यजता। यजत्र। रत्ना।
च। यत्। विऽभजासि। स्वधाऽवः। भागं। नः। अत्र। वसुऽमन्तं। वीतात्। श्रुधि। नः। अग्ने। सदने। सधऽस्थे। ७०

© Dharmartha Trust J&K. Digitized by eGangotri

युक्ष्वा रथं । अमर्तस्य । द्रविल्नुं । आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानां । अप । भूः । इह ।
स्याः ॥ ३० ॥ द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा । देवः । यत् । मर्तान् । यजथा
याय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वं । असुं । यन् । देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यं । प्रथमः । चि
कित्वान् । धूमऽकेतुः । सम्ऽइधा । भाऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥ स्वावृक् । देवस्य । अ
मृतं । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी ।
दिव्यं । घृतं । वाः ॥ अर्चामि । वां । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतं ।
रोदसी इति । मे । अहा । यत् । द्यावः । असुऽनीतिं । अयन् । मध्वा । नः । अत्र । पितरा । शिशीतां ॥ किं । स्वित् ।

© Dharmartha Trust J&K. Digitized by eGangotri

सलक्ष्मायद्विषुरूपाभवाति

प.स. नः। राजा। अग्रहे। कर्त। अस्य। अति। व्रतं। चकृम। कत्। विवेद। मित्रः। चित्। हि। स्म। जुहुराणः। देवान्। श्लो
७३ कः। ना। याता। आपिः। वाजैः। आस्ति। ॥३३॥ दुःऽमंतु। अत्र। अमृतस्य। नाम। यमस्य। यः। मनवते। सुऽमं
तु। अग्ने। तं। ऋष्व। पाहि। अप्रऽयुच्छन्। यस्मिन्। देवाः। विदथे। मादयंते। विवस्वतः। सदने। धारयंते। सू
र्ये। ज्योतिः। अदधुः। मासि। अक्तून्। परि। द्योतनिं। चरतः। अजस्रा। यस्मिन्। देवाः। मन्मनि। संऽचरंति। अ
पीच्ये। न। वयं। अस्य। विद्म। मित्रः। नः। अत्र। अदितिः। अनागान्। सविता। देवः। वरुणाय। वोचत्। ॥१२॥ श्रुधी नो० १
युजे। वां। ब्रह्म। पूर्व्यं। नमःऽभिः। वि। श्लोकः। एतु। पथ्याऽइव। सूरेः। शृण्वंतु। विश्वे। अमृतस्य। पुत्राः। आ।
ये। धामानि। दिव्यानि। तस्थुः। यमेऽइवेति। यमेऽइवायतमाने इति। यत्। एतं। प्र। वां। भरन्। मानुषाः। देवऽ ७३

© Dharmartha Trust J&K. Digitized by eGangotri

यंतः। आ। सीदतं। स्वां। ऊं इति। लोकं। विदाने इति। स्वासस्थे इति सुऽआसस्थे। भवतं। इंदवे। नः। यं। वां। पुर
नि। रूपः। अनु। अरोहं। चतुःऽपदीं। अनु। एमि। व्रतेन। अक्षरेण। प्रति। मिमे। एतां। ऋतस्य। नाभौ। अधि।
सं। पुनामि। देवेभ्यः। कं। अवरणीत। मर्त्यं। प्रऽजायै। कं। अमृतं। न। अवरणीत। बृहस्पतिं। यज्ञं। अकृण्वत।
ऋषिं। प्रियां। यमः। तन्वं। प्र। अरिरेचीत्। सप्त। क्षरंति। शिशवे। मरुत्वते। पित्रे। पुत्रासः। अपि। अवीवृतन्
ऋतं। उभे इति। अस्य। इत्तो। उभयस्य। राजतः। उभे इति। यतेते इति। उभयस्य। पुष्यतः॥ ३३॥ परेयिऽ
वांसं। प्रऽवतः। महीः। अनु। बहुऽभ्यः। पंथां। अनुऽपस्पशानं। वैवस्वतं। संऽगमनं। जनानां। यमं। राजा
नं। हविषा। दुवस्य। यमः। नः। गातुं। प्रथमः। विवेद। न। एषा। गव्यूतिः। अपऽभर्तवै। ऊं इति। यत्र। नः। पू

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ वीऽपितरः। पराऽईयुः। एना। अजज्ञानाः। पथ्याः। अनु। स्वाः। मातली। कव्यैः। यमः। अंगिरःऽभिः। बृहस्पतिः।
७२ ऋक्वऽभिः। ववृधानः। यान्। च। देवाः। ववृधुः। ये। च। देवान्। स्वाहा। अन्ये। स्वधया। अन्ये। मदंति। इमं।
यम। प्रऽस्तरं। आ। हि। सीद। अंगिरःऽभिः। पितृऽभिः। संऽविदानः। आ। त्वा। मंत्राः। कविऽशस्ताः। वहंतु।
एना। राजन्। हविषा। मादयस्व। अंगिरःऽभिः। आ। गहि। यज्ञियेभिः। यम। वैरूपैः। इह। मादयस्व। विव
स्वंतं। हुवे। यः। पिता। ते। अस्मिन्। यज्ञे। बर्हिषि। आ। निऽसद्य॥ ४॥ अंगिरसः। नः। पितरः। नवऽग्वाः।
अथर्वाणः। भृगवः। सोम्यासः। तेषां। वयं। सुऽमतौ। यज्ञियानां॥५॥ प्र। इहि। प्र। इहि। पथिऽभिः। पूर्व्येभिः।
॰उभा। राजाना। स्वधया। मदंता। यमं। पश्यासि। वरुणं। च। देवं। सं। गच्छस्व। पितृऽभिः। सं। यमेन। ७२

© Dharmartha Trust J&K. Digitized by eGangotri

इष्टापूर्तेन।परमे।विऽओमन्।हित्वाय।अवद्यं।पुनः।अस्तं।आ।इहि।सं।गच्छस्व।तन्वा।सुऽवर्चाः।अप।इत।
वि।इत।वि।च।सर्पत।अतः।अस्मै।एतं।पितरः।लोकं।अक्रन्।अहःऽभिः।अत्ऽभिः।अक्तुऽभिः।विऽअक्तं।यमः।
ददाति।अवऽसानं।अस्मै।अति।द्रव।सारमेयौ।श्वानौ।चतुःऽअक्षौ।शबलौ।साधुना।पथा।अथ।पितॄन्।
सुऽविदत्रान्।उप।इहि।यमेन।ये।सधऽमादं।मदन्ति।।१०।।ये।ते।श्वानौ।यम।रक्षितारौ।चतुःऽअक्षौ।पथिर
क्षी इति पथिऽरक्षी।नृऽचक्षसौ।ताभ्यां।एनं।परि।देहि।राजन्।स्वस्ति।च।अस्मै।अनमीवं।च।धेहि।उरुऽन
सौ।असुऽतृपौ।उदुम्बलौ।यमस्य।दूतौ।चरतः।जनान्।अनु।तौ।अस्मभ्यं।दृशये।सूर्याय।पुनः।दातां।असुं।
अद्य।इह।भद्रं।यमाय।सोमं।सुनुत।यमाय।जुहुत।हविः।यमं।ह।यज्ञः।गच्छति।अग्निऽदूतः।अरंऽकृतः।य

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. मायाघृतऽवत्।हविः।०सः।नः।देवेषु।आयमत्।दीर्घं।आयुः।प्र।जीवसे।यमाय।मधुमत्ऽतमं।राज्ञे।
७३ हव्यं।जुहोतन।इदं।नमः।ऋषिऽभ्यः।पूर्वऽजेभ्यः।पूर्वेभ्यः।पथिकृत्ऽभ्यः।त्रिऽकद्रुकेभिः।पतति।षट्।उर्वीः।
एकं।इत्।बृहत्।त्रिऽस्तुप्।गायत्री।छंदांसि।सर्वा।ता।यमे।आऽहिता॥१॥ उत्।ईरतां।अवरे।उत्।परा
सः।उत्।मध्यमाः।पितरः।सोम्यासः।असुं।ये।ईयुः।अवृकाः।ऋतऽज्ञाः।ते।नः।अवंतु।पितरः।हवेषु।इ
दं।पितृऽभ्यः।नमः।अस्तु।अद्य।ये।पूर्वासः।ये।[illegible]।उपरासः।ईयुः।ये।पार्थिवे।रजसि।आ।निऽस
त्ताः।ये।वा।नूनं।सुऽवृजनासु।विक्षु।आ।अहं।पितॄन्।सुऽविदत्रान्।अवित्सि।नपातं।च।विऽक्रम
णं।च।विष्णोः।बर्हिऽसदः।ये।स्वधया।सुतस्य।भजंत।पित्वः।ते।इह।आऽगमिष्ठाः।बर्हिऽसदः।पित ७३

73

© Dharmartha Trust J&K. Digitized by eGangotri

रः। कृती। अर्वाक्। इमा। वः। हव्या। चकृम। जुषध्वं। ते। आ। गत। अवसा। शंऽतमेन। अथ। नः। शं। योः। अरपः।
दधात। उपऽहूताः। पितरः। सोम्यासः। बर्हिऽष्येषु। निऽधिषु। प्रियेषु। ते। आ। गमंतु। ते। इह। श्रुवंतु। अधि।
ब्रुवंतु। ते। अवंतु। अस्मान्॥ ३७॥ आऽअच्य। जानु। दक्षिणतः। निऽसद्य। इमं। यज्ञं। अभि। गृणीत। विश्वे। मा।
हिंसिष्ट। पितरः। केन। चित्। नः। ०। आसीनासः। अरुणीनां। उपऽस्थे। रयिं। धत्त। दाशुषे। मर्त्याय। पुत्रेभ्यः।
पितरः। तस्य। वस्वः। प्र। यच्छत। ते। इह। ऊर्जं। दधात। ये। नः। पूर्वे। पितरः। सोम्यासः। अनुऽऊहिरे। सोमऽपी
थं। वसिष्ठाः। तेभिः। यमः। संऽरराणः। हवींषि। उशन्। उशत्ऽभिः। प्रतिऽकामं। अत्तु। ये। ततृषुः। देवऽत्रा। जे
हमानाः। होत्राऽविदः। स्तोमऽतष्टासः। अर्कैः। आ। अग्ने। याहि। सुऽविदत्रेभिः। अर्वाङ्। सत्यैः। कव्यैः। पितृऽ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ भिः। घर्मसत्ऽभिः। ये। सत्यासः। हविःऽअदः। हविःऽपाः। इन्द्रेण। देवैः। सऽरथम्। दधानाः॥ आ। सहस्रम्। देवऽवन्दैः। प
७४ रैः। पूर्वैः। पितृऽभिः। घर्मसत्ऽभिः॥ ३८॥ अग्निऽस्वात्ताः। पितरः। आ। इह। गच्छत। सदःऽसदः। सदत। सुऽप्रनीतयः।
74 अत्त। हवींषि। प्रऽयतानि। बर्हिषि। अथ। रयिम्। सर्वऽवीरम्। दधातन॥ त्वम्। अग्ने। ईळितः। जातऽवेदः। अवाट्। ह
व्यानि। सुरभीणि। कृत्वी। प्र। अदाः। पितृऽभ्यः। स्वधया। ते। अक्षन्। अद्धि। त्वम्। देव। प्रऽयता। हवींषि॥ ये। च। इ
ह। पितरः। ये। च। न। इह। यान्। च। विद्म। यान्। ऊं इति। च। न। प्रऽविद्म॥ त्वम्। वेत्थ। यति। ते। जातऽवेदः। स्वधाभिः।
यज्ञम्। सुऽकृतम्। जुषस्व॥ ये। अग्निऽदग्धाः। ये। अनग्निऽदग्धाः। मध्ये। दिवः। स्वधया। मादयन्ते॥ तेभिः। स्व
ऽराट्। असुऽनीतिम्। एताम्। यथाऽवशम्। तन्वम्। [illegible]। कल्पयस्व॥ ३९॥ मा। एनम्। अग्ने। वि। दहः। मा। अभि। शोचः। ७४

© Dharmartha Trust J&K. Digitized by eGangotri

मा। अस्य। त्वचं। चिक्षिपः। मा। शरीरं। यदा। शृतं। कृणवः। जातऽवेदः। अथ। ईं। एनं। प्र। हिणुतात्। पितृऽभ्यः।
शृतं। यदा। करसि। जातऽवेदः।०। परि। दत्तात्। पितृऽभ्यः। यदा। गच्छाति। असुऽनीतिं। एतां। अथ। देवानां। व
शऽनीः। भवाति। सूर्यं। चक्षुः। गच्छतु। वातं। आत्मा। द्यां। च। गच्छ। पृथिवीं। च। धर्मणा। अपः। वा। गच्छ। यदि।
तत्र। ते। हितं। ओषधीषु। प्रति। तिष्ठ। शरीरैः। अजः। भागः। तपसा। तं। तपस्व। तं। ते। शोचिः। तपतु। तं। ते। अ
र्चिः। याः। ते। शिवाः। तन्वः। जातऽवेदः। ताभिः। वह। एनं। सुऽकृतां। ऊं इति। लोकं। अव। सृज। पुनः। अग्ने। पितृऽ
भ्यः। यः। ते। आऽहुतः। चरति। स्वधाभिः। आयुः। वसानः। उप। वेतु। शेषः। सं। गच्छतां। तन्वा। जातऽवेदः॥ २०॥
ते। यत्। ते। कृष्णः। शकुनः। आऽतुतोद। पिपीलः। सर्पः। उत। वा। श्वापदः। अग्निः। तत्। विश्वऽअत्। अगदं। कृणो

© Dharmartha Trust J&K. Digitized by eGangotri

१०स० तु।सोमः।च।यः।ब्राह्मणान्।आऽविवेश।अग्नेः।वर्म।परि।गोभिः।व्ययस्व।सं।प्र।ऊर्णुस्व।पीवसा।मेदसा।
७५ च।न।इत्।त्वा।धृष्णुः।हरसा।जर्हृषाणः।दधृक्।विऽधक्ष्यन्।परिऽअंखयाते।इमं।अग्ने।चमसं।मा।वि।जि
ह्वरः।प्रियः।देवानां।उत।सोम्यानां।एषः।यः।चमसः।देवऽपानः।तस्मिन्।देवाः।अमृताः।मादयंते।क्रव्यऽ
अदं।अग्निं।प्र।हिणोमि।दूरं।यमऽराज्ञः।गच्छतु।रिप्रऽवाहः।इह।एव।अयं।इतरः।जातऽवेदाः।देवेभ्यः।ह
व्यं।वहतु।प्रऽजानन्।यः।अग्निः।क्रव्यऽअत्।प्रऽविवेश।वः।गृहं।इमं।पश्यन्।इतरं।जातऽवेदसं।तं।हरा
मि।पितृऽयज्ञाय।देवं।सः।घर्मं।इन्वात्।परमे।सधस्थे।२३।यः।अग्निः।क्रव्यऽवाहनः।पितॄन्।यक्ष
त्।ऋतऽवृधः।प्र।इत्।ऊं।इति।हव्यानि।वोचति।देवेभ्यः।च।पितृऽभ्यः।आ।उशंतः।त्वा।नि।धीमहि।उशं ७५

© Dharmartha Trust J&K. Digitized by eGangotri

तः। सं। इधीमहि। उशन्त। उशतः। आ। वह। पितॄन्। हविषे। अत्तवे। यं। त्वं। अग्ने। सम्ऽअदहः। तं। ऊं इति। निः।
वापय। पुनरिति। कियांबु। अत्र। रोहतु। पाकऽदूर्वा। विऽअल्कशा। शीतिके। शीतिऽकावति। ल्हादिके।
ल्हादिऽकावति। मंडूक्या। सु। सं। गमः। इमं। सु। अग्निं। हर्षय। २२। त्वष्टा। दुहित्रे। वहतुं। कृणोति। इति।
इदं। विश्वं। भुवनं। सं। एति। यमस्य। माता। परिऽउह्यमाना। महः। जाया। विवस्वतः। ननाश। अप। अगू
हन्। अमृतां। मर्त्येभ्यः। कृत्वी। सऽवर्णां। अददुः। विवस्वते। उत। अश्विनौ। अभरत्। यत्। तत्। आसीत्।
अजहात्। ऊं इति। द्वा। मिथुना। सरण्यूः। पूषा। त्वा। इतः। [illegible] च्यावयतु। प्र। विद्वान्। अनष्टऽपशुः। भुव
नस्य। गोपाः। सः। त्वा। एतेभ्यः। परि। ददत्। पितृऽभ्यः। अग्निः। देवेभ्यः। सुऽविदत्रियेभ्यः। आयुः। विश्वऽ

© Dharmartha Trust J&K. Digitized by eGangotri

आशाः।

प.स. आयुः। परि। पासति। त्वा। पूषा। त्वा। पातु। प्रऽपथे। पुरस्तात्। यत्र। आसते। सुऽकृतः। यत्र। ते। ययुः। तत्र। त्वा। दे

७६ वः। सविता। दधातु। पूषा। इमाः। अनु। वेद। सर्वाः। सः। अस्मान्। अभयऽतमेन। नेषत्। स्वस्तिऽदाः। आघृणिः।

सर्वऽवीरः। अप्रऽयुच्छन्। पुरः। एतु। प्रऽजानन्। रू। प्रऽपथे। पथाम्। अजनिष्ट। पूषा। प्रऽपथे। दिवः। प्रऽपथे।

पृथिव्याः। उभे इति। अभि। प्रियतमे इति प्रियऽतमे। सधस्थे इति सधऽस्थे। आ। च। परा। च। चरति। प्रऽजानन्।

सरस्वतीम्। देवऽयन्तः। हवन्ते। सरस्वतीम्। अध्वरे। तायमाने। सरस्वतीम्। सुऽकृतः। अह्वयन्त। सरस्वती। दाशुषे।

वार्यम्। दात्। सरस्वति। या। सऽरथम्। ययाथ। स्वधाभिः। देवि। पितृऽभिः। मदन्ती। आऽसद्य। अस्मिन्। बर्हिषि।

मादयस्व। अनमीवाः। इषः। आ। धेहि। अस्मे इति। सरस्वतीम्। याम्। पितरः। हवन्ते। दक्षिणा। यज्ञम्। अभिऽनक्ष ७६

© Dharmartha Trust J&K. Digitized by eGangotri

माणाः। सहस्रऽअर्घा। इषः। अत्र। भागः। रायः। पोषं। यजमानेषु। धेहि। आपः। अस्मान्। मातरः। शुंधयंतु।
घृतेन। नः। घृतऽप्वः। पुनंतु। विश्वं। हि। रिप्रं। प्रऽवहंति। देवीः। उत्। इत्। आभ्यः। शुचिः। आऽपूतः। एमि। २४। द्र
प्सः। च। स्कंदत्। प्रथमान्। अनु। द्यून्। इमं। च। योनिं। अनु। यः। च। पूर्वः। समानं। योनिं। अनु। संऽचरंतं। द्रप्सं। जु
होमि। अनु। सप्त। होत्राः। यः। ते। द्रप्सः। स्कंदति। यः। ते। अंशुः। बाहुऽच्युतः। धिषणायाः। उपऽस्थात्। अध्व
र्योः। वा। परि। वा। यः। पवित्रात्। तं। ते। जुहोमि। मनसा। वषट्ऽकृतं। ०। स्कन्नः। ०। अवः। च। यः। परः। स्रुचा।
अयं। देवः। बृहस्पतिः। सं। तं। सिंचतु। राधसा। पयस्वतीः। ओषधयः। पयस्वत्। मामकं। वचः। अपां। प
यस्वत्। इत्। पयः। तेन। मा। सह। शुंधत। २५। परं। मृत्यो। इति। अनु। परा। इहि। पंथां। यः। ते। स्वः। इतरः। दे

प॰स॰ वऽयानात्। चक्षुष्मते। शृण्वते। ते। ब्रवीमि। मा। नः। प्रऽजां। रिरिषः। मा। उत। वीरान्। मृत्योः। पदं। योपयंतः।
७७ यत्। ऐत॥०॥ आऽप्यायमानाः। प्रऽजया। धनेन। शुद्धाः। पूताः। भवत। यज्ञियासः। इमे। जीवाः। वि। मृतैः।
आ। अववृत्रन्। अभूत्। भद्रा। देवऽहूतिः। नः। अद्य। प्रांचः। अगाम। नृतये। हसाय॥०॥ इमं। जीवेभ्यः। परिऽ
धिं। दधामि। मा। एषां। नु। गात्। अपरः। अर्थं। एतं। शतं। जीवंतु। शरदः। पुरूचीः। अंतः। मृत्युं। दधतां। पर्वते
ना। यथा। अहानि। अनुऽपूर्वं। भवंति। यथा। ऋतवः। ऋतुऽभिः। यंति। साधु। यथा। नः। पूर्वं। अपरः। जहा
ति। एव। धातः। आयूंषि। कल्पय। एषां॥ रद्धा। आ। रोहत। आयुः। जरसं। वृणानाः। अनुऽपूर्वं। यतमानाः।
यति। स्थ। इह। त्वष्टा। सुऽजनिमा। सऽजोषाः। दीर्घं। आयुः। करति। जीवसे। वः। इमाः। नारीः। अविधवाः। सुऽ ७७

© Dharmartha Trust J&K. Digitized by eGangotri

पत्नीः। आऽअंजनेन। सर्पिषा। सं। विशंतु। अनश्रवः। अनमीवाः। सुऽरत्नाः। आ। रोहंतु। जनयः। योनिं।
अग्रे। उत्। ईर्ष्व। नारि। अभि। जीवऽलोकं। गतऽअसुं। एतं। उप। शेषे। आ। इहि। हस्तऽग्राभस्य। दिधिषोः। त
व। इदं। पत्युः। जनिऽत्वं। अभि। सं। बभूथ। धनुः। हस्तात्। आऽददानः। मृतस्य। अस्मे इति। क्षत्राय। वर्चसे।
बलाय। अत्र। एव। त्वं। इह। वयं। सुऽवीराः। विश्वाः। स्पृधः। अभिऽमातीः। जयेम। उप। सर्प। मातरं। भूमिं। ए
तां। उरुऽव्यचसं। पृथिवीं। सुऽशेवां। ऊर्णऽम्रदाः। युवतिः। दक्षिणाऽवते। एषा। त्वा। पातु। निःऽऋतेः। उपऽ
स्थात्॥२ग॥ उत्। श्वंचस्व। पृथिवि। मा। नि। बाधथाः। सुऽउपायना। अस्मै। भव। सुऽउपवंचना। माता।
पुत्रं। यथा। सिचा। अभि। एनं। भूमे। ऊर्णुहि। उत्ऽश्वंचमाना। पृथिवी। सु। तिष्ठतु। सहस्रं। मितः। उप। हि।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ श्रयंतां। ते। गृहासः। घृतऽश्चुतः। भवंतु। विश्वाहा। अस्मै। शरणाः। संतु। अत्र। उत्। ते। स्तभ्नामि। पृथिवीं।
७८ त्वत्। परि। इमं। लोगं। निऽदधत्। मो इति। अहं। रिषं। एतां। स्थूणां। पितरः। धारयंतु। ते। अत्र। यमः। सदना। ते।
मिनोतु। प्रतीचीने। मां। अहनि। इषाःऽपर्णंऽइव। आ। दधुः। प्रतीचीं। जग्रभ। वाचं। अश्वं। रशनया। यथा।
॥१८॥ इति सप्तमाष्टके षष्ठोध्यायः॥ ॐ॥ म॥ निवर्तध्वमष्टौ मथितो यम गुर्वी वारुणिर्भार्गवश्च्यवनो वा पं
गव्यं चानुष्टुभमग्नीषोमीयो द्वितीयोऽर्द्धर्चः षष्ठी गायत्री सप्तम्योत्तरा ष्व्यैंद्रो विमदः प्राजापत्यो वा वसुकृ
द्वसुकृद्वा मइंद्र दशाग्नेयं तु गायत्रमाद्यैकपदापादएव वा शांत्यर्थः परानुष्टुबंत्ये विराट् त्रिष्टुभा वाग्निं
नाष्टावास्तारपंक्तं कुह पंचोना पुरस्ताद्बृहती त्रिष्टुबंतं त्वं स्याचिदा नस्त्वं नोनुष्टुभो यजामहे सप्ताद्या ७८

© Dharmartha Trust J&K. Digitized by eGangotri

ऽयेत्रिष्टुभौपंचम्यभिसारिणीइंद्रसोमंषळास्तारपांक्तं।वाश्विन्यांयास्तिस्त्रोनुष्टुभोभद्रमेकादशसौ
म्यंप्रहिनवपोऽष्ममानुष्टुभमाद्याचतुर्थ्यौदृष्मिहावसत्सुचतुर्विंशतिरिंद्रोवसुक्रोविश्वोहिद्वादशैंद्र
वसुक्रयोःसंवादऐंद्रंसूक्तस्यप्रथमयेंद्रस्यस्नुषापरोक्षवदिंद्रमाहेंद्रस्ययुजःशेषा-ऋषेश्चतु
र्थीचवनेनाष्टौप्रदेनत्रापंचोनाकवषऐलूषआपमपोनप्त्रीयंवानएकादशवैश्वदेवंप्रस्तगमंना
नवपंचाद्याजगत्यः॥ॐमूः॥नि।वर्तध्वं।मा।अनु।गात।अस्मान्।सिसक्त।रेवतीः।अग्नीषोमा।पुनर्व
सूइतिपुनःऽवसू।अस्मेइति।धारयतं।रयिं।पुनः।एनाः।नि।वर्तय।पुनः।एनाः।नि।आ।कुरु।इंद्रः।ए
नाः।नि।यच्छतु।अग्निः।एनाः।उपऽआजतु।पुनः।एनाः।नि।वर्तत।अस्मिन्।पुष्यंतु।गोऽपतौ।इह।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. एव। अग्ने। नि। धारय। इह। तिष्ठतु। या। रयिः। यत्। निऽयानं। निऽअयनं। संऽज्ञानं। यत्। पराऽअयनं।
७९ आऽवर्त्तनं। निऽवर्त्तनं। यः। गोपाः। अपि। तं। हुवे। यः। उत्ऽआनट्। विऽअयनं। यः। उत्ऽआनट्। पराऽअ
यनं। आऽवर्त्तनं। निऽवर्त्तनं। अपि। गोपाः। नि। वर्त्ततां। आ। निऽवर्त्त। नि। वर्त्तय। पुनः। नः। इंद्र। गाः।
79 देहि। जीवाभिः। भुनजामहै। परि। वः। विश्वतः। दधे। ऊर्जा। घृतेन। पयसा। ये। देवाः। के। च। य
ज्ञियाः। ते। रय्या। सं। सृजंतु। नः। आ। निऽवर्त्तन। वर्त्तय। नि। निऽवर्त्तन। वर्त्तय। भूम्याः। चतस्रः। प्र
ऽदिशः। ताभ्यः। एनाः। नि। वर्त्तय। ३। भद्रं। नः। अपि। वातय। मनः। अग्निं। ईळे। भुजां। यविष्ठं। शा
सा। मित्रं। दुःऽधरीतुं। यस्य। धर्मन्। स्वः। एनीः। सपर्यंति। मातुः। ऊधः। यं। आसा। रुपऽनीळं। भा ७९

© Dharmartha Trust J&K. Digitized by eGangotri

साऽकेतुं।वर्द्धयंति।भ्राजंते।श्रेणिऽदन्।अर्यः।विशां।गातुः।एति।प्रऽयत्।आनट्।दिवः।अंतान्।कविः।अ
भ्रं।दीद्यानः।जुषत।हव्या।मानुषस्य।ऊर्ध्वः।तस्थौ।ऋभ्वा।यज्ञे।मिन्वन्।सद्म।पुरः।एति।सः।हि।क्षे
मः।हविः।यज्ञः।श्रुष्टी।इत्।अस्य।गातुः।एति।अग्निं।देवाः।वाशीऽमंतं।२।यज्ञैः।सहः।दुवः।इषा।अग्निं।
पूर्वस्य।शेवस्य।अद्रेः।सूनुं।आयुं।आ।कृः।नरः।यो।के।चा।अस्मत्।आ।विश्वा।इत्।ते।वामे।आ।स्यु
रिति स्युः।अग्निं।हविषा।वर्द्धंतः।कृष्णः।श्वेतः।अरुषः।यामः।अस्य।ब्रध्नः।ऋज्रः।उत।शोणः।यश
स्वान्।हिरण्यऽरूपं।जनिता।जजान।एव।ते।अग्ने।विऽमदः।मनीषां।ऊर्जः।नपात्।अमृतेभिः।सऽ
जोषाः।गिरः।आ।वक्षत्।सुऽमतीः।इयानः।इषं।ऊर्जं।सुऽक्षितिं।विश्वं।आ।अभारित्यभाः।३।आ।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ अग्निं।न।स्ववृक्तिऽभिः।होतारं।त्वा।वृणीमहे।यज्ञाय।स्तीर्णऽबर्हिषे।वि।वः।मदे।शीरं।पावकऽशोचिषं।
८० विवक्षसे।त्वां।ऊं इति।ते।सुऽआभुवः।भुंमंति।अश्वऽराधसः।वेति।त्वां।उपऽसेचनी।०ऋजीतिः।अग्ने।
आऽहुतिः।विवक्षसे।ते इति।धमार्णः।आसते।जुहूभिः।सिंचतीःऽइव।कृष्णा।रूपाणि।अर्जुना।०वि
80 श्वाः।अधि।श्रियः।धिषे।विवक्षसे।यं।अग्ने।मन्यसे।रयिं।सहसाऽवन्।अमर्त्य।तं।आ।नः।वाजऽ
सातये।०यज्ञेषु।चित्रं।आ।भर।विवक्षसे।अग्निः।जातः।अथर्वणा।विदत्।विश्वानि।काव्या।भुवत्।
दूतः।विवस्वतः।०प्रियः।यमस्य।काम्यः।विवक्षसे।४।त्वां।यज्ञेषु।ईळते।अग्ने।प्रऽयति।अध्वरे।
त्वां।वसूनि।काम्या।०विश्वा।दधासि।दाशुषे।विवक्षसे।०चारुं।अग्ने।नि।सेदिरे।घृतऽप्रतीकं। ८०

त्वां यज्ञेष्वृत्विजं १

© Dharmartha Trust J&K. Digitized by eGangotri

यशश्चक्रे असाम्या ४

मनुषः।०।शुक्रं।चेतिष्ठं।अक्तुऽभिः।विवक्षसे।अग्ने।शुक्रेण।शोचिषा।उरु।प्रथयसे।बृहत्।अभिऽक्रंद
न्।वृषऽयसे।०।गर्भं।दधासि।जामिषु।विवक्षसे।प।कुह।श्रुतः।इंद्रः।कस्मिन्।अद्य।जने।मित्रः।न।श्रू
यते।ऋषीणां।वा।यः।क्षये।गुहा।वा।चर्कृषे।गिरा।इह।श्रुतः।इंद्रः।अस्मे इति।अद्य।स्तवे।वज्री।ऋची
षमः।मित्रः।न।यः।जनेषु।आ।०।महः।यः।पतिः।शवसः।असामि।आ।महः।नृम्णस्य।तूतुजिः।भर्ता।
वज्रस्य।धृष्णोः।पिता।पुत्रंऽइव।प्रियं।युजानः।अश्वा।वातस्य।धुनी इति।देवः।देवस्य।वज्रिऽवः।स्यं
ता।पथा।विरुक्मता।सृजानः।स्तोषि।अध्वनः।त्वं।त्या।चित्।वातस्य।अश्वा।आ।अगाः।ऋज्रा।त्म
ना।वहध्यै।ययोः।देवः।न।मर्त्यः।यंता।नकिः।विदाय्यः।५।अध।ग्मंता।उशना।पृच्छते।वां।कदऽअ

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. र्था।नः।आ।गहि।आऽजग्मथुः।पराकात्।दिवः।च।ग्मः।च।मर्त्यं।आ।नः।इंद्र।पृक्षसे।अस्माकं।ब्रह्म।उत्ऽ
८३ यतं।न।त्वा।याचामहे।अवः।शुष्णं।यत्।हन्।अमानुषं।अकर्मा।दस्युः।अभि।नः।अमंतुः।अन्यऽव्र
तः।अमानुषः।त्वं।तस्य।अमित्रऽहन्।वधः।दासस्य।दंभय।त्वं।नः।इंद्र।शूर।शूरैः।उत।त्वाऽऊतासः।ब
81 र्हणा।पुरुऽत्रा।ते।वि।पूर्तयः।नवंत।क्षोणयः।यथा।त्वं।ता।नः।वृत्रऽहत्ये।चोदयः।नॄन्।कार्पाणे।शूर।
वज्रिऽवः।गुहा।यत्।कवीनां।विशां।नक्षत्रऽशवसां।७।मक्षु।ता।ते।इंद्र।दानऽअप्नसः।आक्षाणे।
शूर।वज्रिऽवः।यत्।ह।शुष्णस्य।दंभयः।जातं।विश्वं।सयाऽवऽभिः।मा।अकुध्र्यक्।इंद्र।शूर।वस्वीः।
अस्मे इति।भूवन्।अभिष्टयः।वयंऽवयं।ते।आसां।सुम्ने।स्याम।वज्रिऽवः।अस्मे इति।ता।ते।इंद्र।सं ८१

© Dharmartha Trust J&K. Digitized by eGangotri

नु। सत्या। अहिंसंतीः। उपऽस्पृशः। विद्याम। यासां। भुजः। धेनूनां। न। वज्रिऽवः। अहस्ता। यत्। अपदी।
वर्द्धत। क्षाः। शचीभिः। वेद्यानां। शुष्णं। परि। प्रऽदक्षिणित्। विश्वऽआयवे। नि। शिश्नथः॥ ३॥ मा। रिषण्यः।
वसवान। वसुः। सन्। उत। त्रायस्व। गृणतः। मघोनः। महः। च। रायः। रेवतः। कृधि। नः॥ ५॥ यज्ञा। मह। इंद्रं।
वज्रऽदक्षिणं। हरीणां। रथ्यं। विऽव्रतानां। प्र। श्मश्रु। दोधुवत्। ऊर्ध्वऽथा। भूत्। वि। सेनाभिः। दयमानः।
वि। राधसा॥ हरी इति। नु। अस्य। या। वने। विदे। वसु। इंद्रः। मघैः। मघऽवा। वृत्रऽहा। भुवत्। ऋभुः। वा
जः। ऋभुक्षाः। पत्यते। शवः। अव। क्ष्णौमि। दासस्य। नाम। चित्। यदा। वज्रं। हिरण्यं। इत्। अथा। रथं।
हरी इति। यं। अस्य। वहतः। वि। सूरिऽभिः। आ। तिष्ठति। मघऽवा। सनऽश्रुतः। इंद्रः। वाजस्य। दीर्घऽश्र

© Dharmartha Trust J&K. Digitized by eGangotri

ततदिदस्य पौंस्यं गृणीमसि ३

प.स. वसः। पतिः। सो इति। चित्र। नु। वृष्टिः। यूथ्या। स्वा। सचा। इंद्रः। श्मश्रूणि। हरिता। अभि। प्रुष्णुते। अव। वेति।

८२ सुऽक्षयं। सुते। मधु। उत्। इत्। धूनोति। वातः। यथा। वनं। यः। वाचा। विऽवाचः। मृध्रऽवाचः। पुरु। सहस्रा।

अशिवा। जघान। ॰। पिताऽइव। यः। तविषीं। ववृधे। शवः। स्तोमं। ते। इंद्र। विऽमदाः। अजीजनन्। अपूर्व्यं।

पुरुऽतमं। सुऽदानवे। विद्म। हि। अस्य। भोजनं। इनस्य। यत्। आ। पशुं। न। गोपाः। करामहे। माकिः। नः।

एना। सख्या। वि। योषुः। तव। च। इंद्र। विऽमदस्य। च। ऋषेः। विद्म। हि। ते। प्रऽमतिं। देव। जामिऽवत्। ॰।

इंद्र। सोमं। इमं। पिब। मधुऽमंतं। चमू इति। सुतं। ॰। सहस्रिणं। पुरुवसो इति पुरुऽवसो। विवक्षसे। त्वां।

यज्ञेभिः। उक्थैः। उप। हव्येभिः। ईमहे। शचीऽपते। शचीनां। ॰। श्रेष्ठं। नः। धेहि। वार्यं। विवक्षसे। यः। पतिः। ८२

वि वो मदे २

© Dharmartha Trust J&K. Digitized by eGangotri

अस्मे ते संतु सख्या शिवानि ३

अस्मे रयिं नि धारय वि वो मदे २

82

वार्याणां। असि। रध्रस्य। चोदिता। इंद्र। स्तोतॄणां। अविता। ०। द्विषः। नः। पाहि। अंहसः। विवक्षसे। युवं। शक्रा।
माया। विना। समीची इति सं ऽ ईची। निः। अमंथतं। वि ऽ मदेन। यत्। ईळिता। नासत्या। निः ऽ अमंथतं। विश्वे।
देवाः। अकृपंत। सं ऽ ईच्योः। निः ऽ पतंत्योः। नासत्यौ। अब्रुवन्। देवाः। पुनः। आ। वहतात्। इति। मधु ऽ मत्।
मे। परा ऽ अयनं। मधु ऽ मत्। पुनः। आ ऽ अयनं। ता। नः। देवा। देवतया। युवं। मधु ऽ मतः। स्कृतं। ३०। भद्रं। नः।
अपि। वातय। मनः। दक्षं। उत। क्रतुं। अध। ते। सख्ये। अंधसः। ०। रणन्। गावः। न। यवसे। विवक्षसे। हृ
दि ऽ स्पृशः। ते। आसते। विश्वेषु। सोम। धामऽसु। अध। कामाः। इमे। मम। ०। वि। तिष्ठंते। वसु ऽ यवः। वि
वक्षसे। उत। व्रता। नि। सोम। ते। प्र। अहं। मिनामि। पाक्या। अध। पिता ऽ इव। सूनवे। ०। मृळ। नः। अभि।

© Dharmartha Trust J&K. Digitized by eGangotri

२१

प॰स॰ चित्ता।व।धात्वा।विवक्षसे।सं।ऊं इति।प्र।यंति।धीतयः।सर्गासः।अवताः।नऽइव।क्रतुं।नः।सोम।जीवसे।

८३ ०।धारय।चमसान्ऽइव।विवक्षसे।तव।त्ये।सोम।शक्तिऽभिः।निःऽकामासः।वि।ऋण्विरे।गृत्सस्य।धीराः।

तवसः।०।ऋजं।गोऽमंतं।अश्विनं।विवक्षसे।३।।पशुं।नः।सोम।रक्षसि।पुरुऽत्रा।विऽस्थितं।जगत्।

83 सं।आ।कृणोषि।जीवसे।विश्वा।संऽपश्यन्।भुवना।विवक्षसे।त्वं।नः।सोम।विश्वतः।गोपाः।अदाभ्यः।

भव।सेध।राजन्।अप।स्त्रिधः।०।मा।नः।दुःऽशंसः।ईशत।विवक्षसे।५।सुऽक्रतुः।वयःऽधेयाय।जागृ सं॰म॰ सोम ३

हि।क्षेत्रवित्ऽतरः।मनुषः।०।द्रुहः।नः।पाहि।अंहसः।विवक्षसे।त्वं।नः।वृत्रहन्ऽतम।इंद्रस्य।इंदो इति।

शिवः।सखा।यत्।सीं।हवंते।संऽइथे।०।युध्यमानाः।तोकऽसातौ।विवक्षसे।अयं।घ।सः।तुरः।मदः।इं ८३

© Dharmartha Trust J&K. Digitized by eGangotri

ऽस्य। वर्द्धिता। प्रियः। अयं। कक्षीवतः। महः॰ मतिं। विप्रस्य। वर्द्धयत्। विवक्षसे। अयं। विप्राय। दाशुषे।
वाजान्। इयर्त्ति। गोऽमतः। अयं। सप्तऽभ्यः। आ। वरं। व्रि॰ अंधं। श्रोणं। च। तारिषत्। विवक्षसे। ॥२॥ प्र। हि।
अच्छ। मनीषाः। स्पार्हाः। यंति। निऽयुतः। प्र। दस्रा। नियुत्ऽरथः। पूषा। अविष्टु। माहिनः। यस्य। त्यत्। महि-
त्वं। वाताप्यं। अयं। जनः। विप्रः। आ। वंसत्। धीतिऽभिः। चिकेत। सुऽस्तुतीनां। सः। वेद। सुऽस्तुतीनां। इंदुः।
न। पूषा। वृषा। अभि। प्सुरः। प्रुषायति। व्रजं। नः। आ। प्रुषायति। मंसीमहि। त्वा। वयं। अस्माकं। देव। पूष
न्। मतीनां। च। साधनं। विप्राणां। च। आऽधवं। प्रतिऽअर्द्धिः। यज्ञानां। अश्वऽहयः। रथानां। ऋषिः। सः।
यः। मनुःऽहितः। विप्रस्य। यवयत्ऽसखः। ॥३॥ आऽधीषमाणायाः। पतिः। शुचायाः। च। शुचस्य। च। वा।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰ स॰ सः॒ऽवा॒यः। अवी॑नां। आ। वा॒सां॑सि। मर्मृ॑जत्। इ॒नः। वा॒जानां॑। पतिः॑। इ॒नः। पु॒ष्टी॒नां॑। सखा॑। प्र। श्मश्रु॑। हर्य॑तः।
८४ दू॒धो॒त्। वि। वृथा॑। यः। अदा॑भ्यः। आ। ते॒। रथ॑स्य। पू॒ष॒न्। अ॒जाः। धुरं॑। व॒वृ॒त्युः। विश्व॑स्य। अ॒र्थिनः॑। सखा॑।
84 स॒नः॒ऽजाः। अन॑पऽच्युतः। अ॒स्माकं॑। ऊ॒र्ज्ञौ। रथं॑। पू॒षा। अ॒वि॒ष्टु। माहि॑नः। भु॒व॒त्। वा॒जानां॑। वृ॒धः। इ॒मं। नः॒।
हवे। शृ॒णवत्॑। ३४। अस॑न्तां। मि॒ऽज॒रि॒ता॒रि॒ति। सः। अ॒भिऽवे॒गः। यत्। सु॒न्वते॑। यज॑मानाय। शिक्ष॑। अना॑शीःऽदां। सु।
अ॒हं। अ॒स्मि॒। प्र॒ऽहं॒ता। स॒त्यःऽध्व॒तं। वृ॒जि॒नऽयं॒तं। आ॒भुं। य॒दि। इ॒त्। अ॒हं। यु॒धये॑। सं॒ऽनया॑नि। अदे॑वऽयू॒
न्। त॒न्वा॑। शू॒शु॒जा॒ना॒न्। अ॒मा। ते॒। तुम्रं॑। वृ॒ष॒भं। प॒चा॒नि॒। ती॒व्रं। सु॒तं। प॒ञ्च॒ऽद॒शं। नि। सिं॒चं॒। न। अ॒हं। तं।
वे॒दा॒यः। इति॑। अ॒ब्र॒वीत्। अदे॑वऽयू॒न्। सं॒ऽअ॒र॒णे॒। ज॒घ॒न्वा॒न्। य॒दा। अ॒व॒ऽअ॒ख्य॒त्। सं॒ऽअ॒र॒णं। ऋ॒घा॒व॒त्। ८४

© Dharmartha Trust J&K. Digitized by eGangotri

आत्वा।इन्द्रा।हि।मे।वृषभ।आ।प्र।ब्रुवंति।यत्।अज्ञातिषु।रजनेषु।आसां।विश्वे।सतः।मघऽवानः।मे।आस
न्।आजि।नामि।वा।इन्द्र।क्षेमे।आ।सं।ते।आ।मुं।प्राल।क्षिणां।पर्वते।पादऽगृह्य।ना।वै।ऊं इति।मां।रजने।वा
रयंले।ना।पवैता।सः।यत्।अहं।मनस्यो।मम।स्वनात्।रुधुऽकर्णः।मया।ले।एवा।इन्द्र।अनु।सून्।किरणः
सं।एजात्।ला।ख्या।दर्शन्।अनु।अत्र।मृतु।पान्।अनिंद्रान्।बा।ऊ।ऽक्षदः।शरे।वा।पत्यमानं।घर्षुं।वा।यो।नि ना
निदुः।सखायं।अधि।ऊं इति।नु।एषु।पवयः।ववृत्युः।अमूः।ऊं इति।ओक्षीः।वि।ऊं इति।आयुः।आ
नर्दू।दर्षत्।अनु।पूर्वः।अपरः।नु।दर्षत्।द्वे इति।पवस्ते इति।परि।तं।ना।भूतः।यः।अस्य।पारे।रजसः।वि
वेष।गातेः।यवं।प्रऽयुताः।अर्यः।अशन्।ताः।अपश्यं।सहऽगोपाः।चरंतीः।हवाः।इत्।अर्यः।अभितः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ सं। आऽयन्। कियत्। आसुः। स्वःऽपतिः। छंदयाते। सं। यत्। वयं। यवसऽअदः। जनानां। अहं। यवःऽअदः। उरुऽ
८५ अज्रे। अंतः। इति। अत्र। युक्तः। अनःऽसा। नारं। इच्छात्। अथो इति। अयुक्तं। युनजत्। ववन्वान्। अत्र। इत्।
ऊं इति। मे। मंसते। सत्यं। उक्तं। द्विऽपात्। च। यत्। चतुःऽपात्। संऽसृजानि। स्त्रीभिः। यः। अत्र। वृषणं। पृतन्या
त्। अयुद्धः। अस्य। वि। भजानि। वेदः। १४। यस्य। अनक्षा। दुहिता। जातु। आस। कः। तां। विद्वान्। अभि।
मन्याते। अंधां। कतरः। मेनिं। प्रति। तं। मुचाते। यः। ईं। वा। वरेऽयात्। कियती। योषा। मर्यतः। वधूऽयोः।
परिऽप्रीता। पन्यसा। वार्येण। भद्रा। वधूः। भवति। यत्। सुऽपेशाः। स्वयं। सा। मित्रं। वनुते। जने। चि
त्। पत्तः। अगारा। प्रत्यंचं। अत्ति। शीर्ष्णा। शिरः। प्रति। दधौ। वरूथं। आसीनः। ऊर्ध्वां। उपसि। क्षिणाति। ८५

वहाते। यः। ईं।

© Dharmartha Trust J&K. Digitized by eGangotri

अन्यस्या वेत्वं रिहन्तामि मा यक यायुवा निदघे घेमुरूघः ।१

न्यङ्ः। उन्नानां। अनु। एति। म्रमिं। वहनं। अच्छायः। अपलाशः। अर्वां। तस्थौ। माता। विऽसितः। आर्ति। गर्भः। सिन्ना
वीरासः। अपरात्। उन्नत्। आयन्। अशा। उन्नरात्। नां। तत्। सं। अजग्मिरन्। नो। न। वां। पश्वा। नात्। आखि। विऽमंतः। आयु
न्नादशा। प्राव्हा। सानु। विं। तिरंति। अश्वनः। ३। दशानां। एकं। कपिलं। समानं। तं। हिन्वंति। क्रतवे। पार्याय। ग
र्भं। माता। सुऽधितं। वक्षणासु। अवेनंतं। तुषयंती। बिभर्ति। पीवानं। मेषं। अपचंत। वीराः। निऽउप्ताः। अक्षाः।
अनु। दीवे। आसन्। द्वा। धनुं। बृहतीं। अप्ऽसु। अंतः। रिति। पवित्रऽवंता। चरतः। पुनंता। ३। विऽक्रोशनासः। वि
ष्वंचः। आयन्। पचाति। नेमः। नहि। पक्षत्। अर्धः। अयं। मा। देवः। सविता। तत्। आह। द्रुऽअन्नः। इत्। वनवत्।
सर्पिःऽअन्नः। अपश्यं। ग्रामं। वहमानं। आरात्। अचक्रया। स्वधया। वर्तमानं। सिसक्ति। अर्यः। प्रा युगा।

© Dharmartha Trust J&K. Digitized by eGangotri

प.स. जनानां।सदः।शिक्षा।प्रऽमिनानः।नवीयान्।एतौ।मेऽगावौ।प्रऽमरस्य।युक्तौ।मो।इति।सु।प्र।सेधीः।मु
८६ ऽजः।इत्।नाम।मे।धि।आपः।चित्।अस्य।वि।नशंति।अर्थं।सूरः।च।मुर्कः।उपरः।बभूवान्।३८।अयं।यः।व
ज्रः।पुरुधा।विऽवृत्तः।अवः।सूर्यस्य।बृहतः।पुरीषात्।श्रवः।इत्।एना।परः।अन्यत्।आस्ति।तत्।अव्य
थी।जरिमाणः।तरंति।रक्षोऽरक्षो।निऽयता।मीमयत्।गोः।ततः।वयः।प्र।पतान्।पुरुषऽअदः।अथ।इ
दं।विश्वं।भुवनं।भयाते।इंद्राय।सुन्वत्।ऋषये।च।शिक्षत्।देवानां।माने।प्रथमाः।अतिष्ठन्।कृंतत्रा
त्।एषां।उपराः।उत्।आयन्।त्रयः।तपंति।पृथिवीं।अनूपाः।द्वा।बृबूकं।वहतः।पुरीषं।सा।ते।जीवा
तुः।उत।तस्य।विद्धि।मा।स्म।एता।दृक्।अप।गूहः।सऽमर्ये।आविः।स्वऽरिति स्वः।रुणुते।गूहते।बुसं। ८६

86

© Dharmartha Trust J&K. Digitized by eGangotri

सः। पादुः। अस्य। निःऽनिजः। न। मुच्यते॥ ३९॥ विश्वः। हि। अन्यः। अरिः। आऽजगाम। मम। इत्। अह। श्वशु
रः। न। आ। जगाम। जक्षीयात्। धानाः। उत। सोमं। पपीयात्। सुऽआशितः। पुनः। अस्तं। जगायात्। सः। रोरु
वत्। वृषभः। तिग्मऽशृंगः। वर्ष्मन्। तस्थौ। वरिमन्। आ। पृथिव्याः। विश्वेषु। एनं। वृजनेषु। पामि। यः। मे। कुक्षी
इति। सुतऽसोमः। पृणाति। अद्रिणा। ते। मंदिनः। इंद्र। तूयान्। सुन्वंति। सोमान्। पिबसि। त्वं। एषां। पचंति।
ते। वृषभान्। अत्सि। तेषां। पृक्षेण। यत्। मघऽवन्। हूयमानः। इदं। सु। मे। जरितः। आ। चिकिद्धि। प्रतिऽईपं। शा
पं। नद्यः। वहंति। लोपाशः। सिंहं। प्रत्यंचं। अत्सारिति। क्रोष्टा। वराहं। निः। अतक्त। कक्षात्। कथा। ते। एतत्।
अहं। आ। चिकेतं। गृत्सस्य। पाकः। तवसः। मनीषां। त्वं। नः। विद्वान्। ऋतुऽथा। वि। वोचः। यं। अर्द्धं। ते। मघऽ

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. वन्नाक्षेम्या। धूः। एवा। हि। मां। तवसं। वर्द्धयंति। दिवः। चित्। मे। बृहतः। उत्ऽतरा। धूः। पुरु। सहस्रा। नि। शिशा
८७ मि। साकं। अशत्रुं। हि। मा। जनिता। जजान। २०॥ ॲं। जु। तु। उग्रं। कर्मन्ऽकर्मन्। वृषणं। इंद्र। देवाः। वधीं। वृत्रं। वज्रे
87
णा। मंदसानः। अप। व्रजं। महिना। दाशुषे। वं। देवासः। आयन्। परशून्। अबिभ्रन्। वना। वृश्चंतः। अभि। विट्ऽ
भिः। आयन्। नि। सुऽद्र्वं। दधतः। वक्षणासु। यत्र। कृपीटं। अनु। तत्। दहंति। शशः। क्षुरं। प्रत्यंचं। जगार। अद्रिं। लो
गेन। वि। अभेदं। आरात्। बृहंतं। चित्। ऋहते। रंधयानि। वयत्। वत्सः। वृषभं। शूशुवानः। सुऽपर्णः। इत्था। नु
खं। आ। सिसाय। अवऽरुद्धः। परिऽपदं। न। सिंहः। निऽरुद्धः। चित्। महिषः। तर्ष्यावान्। गोधा। तस्मै। अयथं।
कर्षत्। एतत्। यत्। ब्रह्मणः। प्रतिऽपीयंति। अन्नैः। सिमः। उक्ष्णः। अवऽसृष्टान्। अदंति। स्वयं। बलानि। तन्वः। ८७
तेभ्यः। गोधाः। अयथं। कर्षत्। एतत्।

© Dharmartha Trust J&K. Digitized by eGangotri

ऽरण्या। नाः। एते। शमीभिः। सुऽशमी। अभूवन्। ये। हिन्विरे। तन्वः। सोमे। उक्थैः। नृऽवत्। वदन्। उप। नः। मा
हि। वाजान्। दिवि। श्रवः। दधिषे। नाम। वीरः। २३॥ वने। न। वा। यः। नि। अधायि। चाकन्। शुचिः। वां। स्तोमः।
भुरणौ। अजीगरिति। यस्य। इत्। इंद्रः। पुरुऽदिनेषु। होता। नृणां। नर्यः। नृऽतमः। क्षपाऽवान्। प्र। ते। अस्याः। उ
षसः। प्र। अपरस्याः। नृतौ। स्याम। नृऽतमस्य। नृणां। अनु। त्रिऽशोकः। शतं। आ। अवहत्। नॄन्। कुत्सेन। रथः।
यः। असत्। ससऽवान्। कः। ते। मदः। इंद्र। रंत्यः। भूत्। दुरः। गिरः। अभि। उग्रः। वि। धाव। कत्। वाहः। अर्वाक्।
उप। मा। मनीषा। आ। त्वा। शक्यां। उपऽमं। राधः। अन्नैः। कत्। ऊं इति। द्युम्नं। इंद्र। त्वाऽवतः। नॄन्। कया। धि
या। करसे। कत्। नः। आ। अगन्। मित्रः। न। सत्यः। उरुऽगाय। भृत्यै। अन्ने। समस्य। यत्। असन्। मनीषाः३॥

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. प्राईरयाःस्वरः।अर्थी।ना।पारं।यो।अस्य।काम।जनिधाःऽइव।ग्मन्।गिरः।चायो।ते।तुविऽजात।पूर्वीः।नरः।इंद्र।प्र
८८ निःशिक्षं।ति।अन्नैः।ररा।मात्रेइति।नु।ते।सुमितेइति।सुऽमिते।इंद्र।पूर्वीइति।द्यौः।मज्मना।पृथिवी।काव्येन।
वराय।ते।घृतऽवंतः।सुतासः।स्वा।द्मन्।भवंतु।पीतये।मधूनि।आ।मध्वः।अस्मै।अ।सिचन्।अमत्रं।इंद्राय।
88 पूर्णं।सः।हि।सत्यऽराधाः।सः।ववृधे।वरिमन्।आ।पृथिव्याः।अभि।क्रत्वा।नर्यः।पौंस्यैः।च।वि।आनट्।इं
द्रः।पतना।सुऽओजाः।आ।अस्मै।यतंते।सख्याय।पूर्वीः।आ।स्म।रथं।न।पृतनासु।तिष्ठ।यं।भद्रया।
सुऽमत्या।चोदयासे।॥२३॥त्वं।देवऽत्रा।ब्रह्मणे।गातुं।एतु।अपः।अच्छ।मनसः।नऽप्रऽयुक्ति।महीं।मित्रस्य।
वरुणस्य।धासिं।पृथुऽज्रयसे।रीरधा।सुऽवृक्तिं।अध्वर्यवः।हविष्मंतः।हि।भूत।अच्छ।अपः।इत।उशतीः। ८८

उशंतः।अव।याः।चष्टे।अरुणः।सुऽपर्णः।तं।आ।अस्य[illegible]ध्वं।ऊर्मिं।अद्य।सुऽहस्ताः।अध्वर्यवः।अपः।इ
त।समुद्रं।अपां।नपातं।हविषा।यजध्वं।सः।वः।ददत्।ऊर्मिं।अद्य।सुऽपूतं।तस्मै।सोमं।मधुऽमंतं।सु
नोत।यः।अनिध्मः।दीदयत्।अप्ऽसु।अंतः।यं।विप्रासः।ईळते।अध्वरेषु।अपां।नपात्।मधुऽमतीः।
अपः।दाः।याभिः।इंद्रः।ववृधे।वीर्याय।याभिः।सोमः।मोदते।हर्षते।च।कल्याणीभिः।युवतिऽभिः।न
इहि। मर्यः।ताः।अध्वर्यो इति।अपः।अछ।परा।यत्।आऽसिंचाः।ओषधीभिः।पुनीतात्।।२४।।एव।इत्।
यूने।युवतयः।नमंत।यत्।ईं।उशन्।उशतीः।एति।अछ।सं।जानते।मनसा।सं।चिकित्रे।अध्वर्यवः।
धिषणा।आपः।च।देवीः।यः।वः।वृताभ्यः।अकृणोत्।ऊं इति।लोकं।यः।वः।मह्याः।अभिऽशस्तेः।अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ मुंचत।तस्मै।इंद्राय।मधुऽमंतं।ऊर्मिं।देवऽमादनं।प्र।हिणोतन।आपः।प्र।अस्मै।हिनोत।मधुऽमंतं।ऊर्मिं।
८१ गर्भः।यः।वः।सिंधवः।मध्वः।उत्सः।घृतऽपृष्ठं।ईड्यं।अध्वरेषु।आपः।रेवतीः।शृणुत।हवं।मे।तं।सिंधवः।
89 मत्सरं।इंद्रऽपानं।ऊर्मिं।प्र।हेत।यः।उभे इति।इयर्ति।मदऽच्युतं।औशानं।नभःऽजां।परि।त्रिऽतंतुं।विऽच
रंतं।उत्सं।आऽववर्ततीः।अध।द्विऽधाराः।गोषुऽयुधः।न।निऽयवं।चरंतीः।ऋषे।जनित्रीः।भुवनस्य।
पत्नीः।अपः।वंदस्व।सऽवृधः।सऽयोनीः॥२५॥हिनोत।नः।अध्वरं।देवऽयज्या।हिनोत।ब्रह्म।सनये।
धनानां।ऋतस्य।योगे।वि।स्यध्वं।ऊधः।श्रुष्टीऽवरीः।भूत।न।अस्मभ्यं।आपः।आपः।रेवतीः।क्षयथ।
हि।वस्वः।क्रतुं।च।भद्रं।बिभृथ।अमतं।च।रायः।च।स्थ।स्वऽअपत्यस्य।पत्नीः।सरस्वती।तत्।गृणते। ८१

वयः। धात्त्। प्रति। यत्। आपः। अदृश्रं। आऽयतीः। घृतं। पयांसि। बिभ्रतीः। मधूनि। अध्वर्युऽभिः। मनसा।
संऽविदानाः। इंद्राय। सोमं। सुऽसुतं। भरंतीः। आ। इमाः। अग्मन्। रेवतीः। जीवऽधन्याः। अध्वर्यवः। साद्
यत। सखायः। नि। बर्हिषि। धत्तन। सोम्या। सः। अपां। नप्त्रा। संऽविदाना। सः। एनाः। आ। अग्मन्। आपः।
उशतीः। बर्हिः। आ। इदं। नि। अध्वरे। अदेसेन्। देवऽयंतीः। अध्वर्यवः। सुनुत। इंद्राय। सोमं। अभूत्। ऊं इति।
वः। सुऽशका। देवऽयज्या। रध। आ। नः। देवानां। उप। वेतु। शंसः। विश्वेभिः। तुरैः। अवसे। यजत्रः। तेभिः।
वयं। सुऽसखायः। भवेम। तरंतः। विश्वा। दुःऽइता। स्याम। परि। चित्। मर्त्तः। द्रविणं। ममन्यात्। ऋत
स्य। पथा। नमसा। आ। विवासेत्। उत। स्वेन। क्रतुना। सं। वदेत। श्रेयांसं। दक्षं। मनसा। जगृभ्यात्।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. अधा।यि।धीतिः।असस्यग्रे।अंशोः।तीर्थे।न।दस्मं।उप।यंति।ऊमाः।अभि।आनश्म।सुविलस्य।भूषं।
९० नवेदसः।अमृतानां।अभूम।निस्यं।चाकन्यात्।स्वःऽपतिः।दमूनाः।यस्मै।ऊं इति।देवः।सविता।जजा
९० न।भगः।वा।गोभिः।अर्यमा।ईं।अनज्यात्।सः।अस्मै।चारुः।छदयत्।उत।स्यात्।इयं।सा।भूयाः।
उषसांऽइव।क्षाः।यत्।ह।क्षुऽमंतः।शवसा।संऽआयन्।अस्य।स्तुतिं।जरितुः।भिक्षमाणाः।आ।नः।
शग्मासः।उप।यंतु।वाजाः।२७।अस्य।इत्।एषा।सुऽमतिः।पप्रथाना।अभवत्।पूर्व्या।भूमना।
गौः।अस्याः।सऽनीळाः।असुरस्य।योनौ।समाने।आ।भरणे।बिभ्रमाणाः।किं।स्वित्।वनं।कः।ऊं
इति।सः।वृक्षः।आस।यतः।द्यावा।पृथिवी इति।निःऽततक्षुः।संतस्थाने इति संऽतस्थाने।अजरे इति। १०

© Dharmartha Trust J&K. Digitized by eGangotri

इतऊतीइनीतःऽऊती।अहानि।पूर्वीः।उषसः।जरंता।ना।एतावत्।एना।परः।अन्यत्।अस्ति।उक्षा।सः।द्या
वापृथिवीइति।बिभर्ति।त्वचं।पवित्रं।कृणुत।स्वधाऽवान्।यत्।ईं।स्यै।ना।हरितः।वहंति।स्तेगः।ना।क्षां।
अति।एति।पृथ्वीं।मिहा।ना।वातः।वि।ह।वाति।भूम।मित्रः।यत्।वरुणः।अज्यमानः।अग्निः।वनेन।वि।
असृष्ट।शोकं।स्तरीः।यत्।स्तुता।सयः।अज्यमाना।व्यथिः।अव्यथीः।कृणुत।स्वऽगोपा।पुत्रः।यत्।पूर्वः।
पित्रोः।जनि।शाम्यां।गौः।जगार।यत्।ह।पृच्छान्।उत।कण्वं।नृऽसदः।पुत्रं।आहुः।उत।श्यावः।धनं।आ।
अदत्त।वाजी।प्र।कृष्णाय।रुशत्।अपिन्वत।ऊधः।ऋतं।अत्र।नकिः।अस्मै।अपीपेत्।सत्या।प्रा।सुगम्मं
ना।धियसाना।स्या।सक्षणि।वरेभिः।वरान्।अभि।सु।प्रऽसीदतः।अस्माकं।इंद्रः।उभयं।जुजोषति।यत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१० स. सोम्यस्य। अंधसः। बुबोधति॥ वि। इंद्र। यासि। दिव्यानि। रोचना। वि। पार्थिवानि। रजसा। पुरुऽस्तुत। ये। त्वा।
११ वहंति। मुहुः। अध्वरान्। उप। ते। सु। वन्वंतु। वग्वनान्। अराधसः॥ तत्। इत्। मे। छंत्सत्। वपुषः। वपुःऽतरं।
पुत्रः। यत्। जानं। पित्रोः। अधिऽइयति। जाया। पतिं। वहति। वग्नुना। सुऽमत्। पुंसः। इत्। भद्रः। वहतुः। परिऽ
कृतः॥ तत्। इत्। सधऽस्थं। अभि। चारु। दीधय। गावः। यत्। शासन्। वहतुं। न। धेनवः। माता। यत्। मंतुः।
यूथस्य। पूर्व्या। अभि। वाणस्य। सप्तऽधातुः। इत्। जनः॥ प्र। वः। अच्छ। रिरिचे। देवऽयुः। पदं। एकः। रुद्रेभिः।
याति। तुर्वणिः। जरा। वा। येषु। अमृतेषु। दावने। परि। वः। ऊमेभ्यः। सिंचत। मधु॥ २९॥ निऽधीयमानं।
अपऽगूळ्हं। अप्ऽसु। अक्षेत्रऽवित्। क्षेत्रऽविदं। हि। अप्राट्। सः। प्र। एति। क्षेत्रऽविदा। अनुऽशिष्टः। एत ११

प्रमेदेवानांव्रतपाउवाच। इंद्रोविद्वाँअनुहि
त्वाचचक्षतेनाहमग्नेअनुशिष्टआगा॥ २

© Dharmartha Trust J&K. Digitized by eGangotri

त्वा। वै। भद्रं। अनुऽशासनस्य। गुता। स्तुतिं। विंदति। अंजसीनो। अया। इत्वा। ऊं। इति। प्र। आनीत्वा। अममन्वा। इमा। अ
ह्वा। अपिऽवतः। अपयन्वा। मातुः। ऊधः। आ। ई। एनं। आपा। जरिमा। युवानं। अहेळन्वा। वसुः। सुऽमनाः। बभूव। ए
तानि। भद्रा। कलशा। क्रियाम। कुरुऽश्रवणात्। ददतः। मघानि। दानः। इत्वा। वः। मघऽवानः। सः। अस्तु। अयं। वः। सो
मः। हृदि। यं। बिभर्मि॥ ३०॥ इति सप्तमाष्टके रष्टमोऽध्यायः॥ ओं म्॥ प्रमाया वैश्वदेव्यैंद्रः प्रगाथः परा गायत्र्यो
हे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिर्नेमित्रातिथौ राज्ञि नस्नेहादृषिरुपमश्रवसं पुत्रमस्य
व्यशोकयत्स्मा वेपाः प्रकृ नामौजवान्वाक्षोक्षकृषिप्रशंसा चाक्षाकितवनिंदा च सप्तमी जगत्यबुधं कुशो
धानाको वैश्वदेवं नु द्वित्रिष्टुबंतं लुषासानक्ता नमो द्वादश सौर्यो अभितपाः सौर्यं आगते वै त्रिष्टुब्द्वादशास्यासि

© Dharmartha Trust J&K. Digitized by eGangotri

संमातपंत्यभितः सपत्नीरिवपर्शवः।४ मूषोनशिश्नाव्यदंतिमाध्यस्तोतारंते शतक्रतो।५

१·स· न्त्रः पंचमुक्षणानिंद्रो यो सांषण्मूनाकाक्षीवतो घोषाश्विनेहित्रिष्टुबंतंरथंयांतंसमातुंतचैसुहस्त्यो घोषेयो
९२ स्तेवैकादशाकृष्णोछामेद्वित्रिष्टुबंतंस्त्वायात्विति त्रिष्टुबादिदिवस्यरिद्वादशवत्सप्रिराग्नेयंतु॥ ॥ॐम॥
त्रा।मा।युयुज्रे।प्रऽयुजेः।जनो।नो।वहामि।स्मा।पूषणे।अंतरेण।विश्वे।देवासः।अध।मां।अरक्षन्।दुःऽशासुः।
आ।अगात्।इति।घोषः।आसीत्।निबाधते।अमतिः।नग्नता।जसुः।वेः।न।वेवीयते।मतिः।सुकृत्।सु
नः।मघऽवन्।इंद्र।मृळय।अध।पिताऽइव।नः।भर।कुरुऽश्रवणं।अरणि।राजानं।त्रासदस्यवं।मंहिष्ठं।वाघ
तां।ऋषिः।यस्य।मा।हरितः।रथे।तिस्रः।वहंति।साधुऽया।स्तवै।सहस्रऽदक्षिणे।।३।। यस्य।प्रऽस्वादसः।गि
रः।उपमऽश्रवसः।पितुः।क्षेत्रं।न।रण्वं।ऊचुषे।अधि।पुत्र।उपमऽश्रवः।नपात्।मित्रऽअतिथेः।इहि।पितुः। ९२

© Dharmartha Trust J&K. Digitized by eGangotri

ते। अस्मि। वंदिता। यत्र। ईशीय। अमृतानां। उत। वा। मर्त्यानां। जीवेत्। इत्। मघऽवा। मम। न। देवानां। आत्ति। व्रतं।
शतऽओ। मा। च। न। जीवति। तथा। युजा। वि। च। वर्त्ते॥ १॥ प्रा। वेपाः। मा। बृहतः। मादयंति। प्रवातेऽजाः। इरिणे। व
र्वृतानाः। सोमस्यऽइव। मौजऽवतस्य। भक्षः। विऽभीदकः। जागृविः। मह्यं। अच्छान्। न। मा। मिमेथ। न। जिही
ळे। एषा। शिवा। सखिऽभ्यः। उत। मह्यं। आसीत्। अक्षस्य। अहं। एकऽपरस्य। हेतोः। अनुऽव्रतां। अप। जायां।
अरोधं। द्वेष्टि। श्वश्रूः। अप। जाया। रुणद्धि। न। नाथितः। विंदते। मर्डितारं। अश्वस्यऽइव। जरतः। वस्न्यस्य।
न। अहं। विंदामि। कितवस्य। भोगं। अन्ये। जायां। परि। मृशंति। अस्य। यस्य। अगृधत्। वेदने। वाजी। अक्षः।
पिता। माता। भ्रातरः। एनं। आहुः। न। जानीमः। नयत। बद्धं। एतं। यत्र। आऽदीध्ये। न। दविषाणि। एभिः। परा

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ यत्ऽभ्यः।अव।हीये।सखिऽभ्यः।निऽउप्ताः।च।बभ्रवः।वाचं।अक्रत।एमि।इत्।एषां।निःऽकृतं।जारिणीऽइव॥
९२ ५।सभां।एति।कितवः।पृच्छमानः।जेष्यामि।इति।तन्वा।शूशुजानः।अक्षासः।अस्य।वि।तिरंति।कामं।प्र
तिऽदीव्ने।दधतः।आऽकृतानि।अक्षासः।इत्।अंकुशिनः।निऽतोदिनः।निऽकृत्वानः।तपनाः।तापयिष्णवः।
93 कुमारऽदेष्णाः।जयतः।पुनःऽहनः।मध्वा।संऽपृक्ताः।कितवस्य।बर्हणा॥ त्रिऽपंचाशः।क्रीळति।व्रातः।एषां।
देवःऽइव।सविता।सत्यऽधर्मा।उग्रस्य।चित्।मन्यवे।न।नमंते।राजा।चित्।एभ्यः।नमः।इत्।कृणोति।
नीचाः।वर्त्तंते।उपरि।स्फुरंति।अहस्तासः।हस्तऽवंतं।सहंते।दिव्याः।अंगाराः।इरिणे।निऽउप्ताः।शीताः।
संतः।हृदयं।निः।दहंति॥ जाया।तप्यते।कितवस्य।हीना।माता।पुत्रस्य।चरतः।क्व।स्वित्।ऋणऽवा।बि ९३

© Dharmartha Trust J&K. Digitized by eGangotri

स्तेनाः। धनं। इछमानः। अन्येषां। अस्तं। उप। नक्तं। एति॥ २॥ स्त्रियं। दृष्ट्वाय। कितवं। तताप। अन्येषां। जायां।
सुऽकृतं। च। योनिं। पूर्वाह्णे। अश्वान्। युयुजे। हि। बभ्रून्। सः। अग्नेः। अंते। वृषलः। पपाद। यः। वः। सेनाऽनीः।
महतः। गणस्य। राजा। व्रातस्य। प्रथमः। बभूव। तस्मै। कृणोमि। न। धना। रुणध्मि। दश। अहं। प्राचीः। तत्। ऋ
तं। वदामि। अक्षैः। मा। दीव्यः। कृषिं। इत्। कृषस्व। वित्ते। रमस्व। बहु। मन्यमानः। तत्र। गावः। कितव। तत्र। जा
या। तत्। मे। वि। चष्टे। सविता। अयं। अर्यः। मित्रं। कृणुध्वं। खलु। मृळत। नः। मा। नः। घोरेण। चरत। अभि। धृ
नु। ष्णु। नि। वः। मन्युः। विशतां। अरातिः। अन्यः। बभ्रूणां। प्रऽसितौ। नु। अस्तु॥ ५॥ अबुध्रं। ऊं इति। त्ये। इंद्रऽवं
तः। अग्नयः। ज्योतिः। भरंतः। उषसः। विऽउष्टिषु। मही इति। द्यावा। पृथिवी इति। चेततां। अपः। अद्य। देवानां।

© Dharmartha Trust J&K. Digitized by eGangotri

१०स० अवः। आ। वृणीमहे। दिवः। पृथिव्योः। अवः। आ। वृणीमहे। मातृन्। सिंधून्। पर्वतान्। शर्यणाऽवतः। अना
९४ गाःऽत्वं। सूर्यं। उषसं। ईमहे। भद्रं। सोमः। सुवानः। अद्य। कृणोतु। नः। द्यावा। नः। अद्य। पृथिवी इति। अना
95 गसः। मही इति। त्रायेतां। सुविताय। मातरा। उषाः। उच्छंती। अप। बाधतां। अघं। स्वस्ति। अग्निं। संऽइधा
नं। ईमहे। इयं। नः। उस्रा। प्रथमा। सुऽदेव्यं। रेवत्। सनिऽभ्यः। रेवती। वि। उच्छतु। आरे। मन्युं। दुःऽविदत्रस्य।
धीमहि। ०। प्र। याः। सिस्रते। सूर्यस्य। रश्मिऽभिः। ज्योतिः। भरंतीः। उषसः। विऽउष्टिषु। भद्राः। नः। अद्य। श्र
वसे। वि। उच्छत। ०। द्या। अनमीवाः। उषसः। आ। चरंतु। नः। उत्। अग्नयः। जिहतां। ज्योतिषा। बृहत्। अयु
क्षातां। अश्विना। तूतुजिं। रथं। ०। श्रेष्ठं। नः। अद्य। सवितः। वरेण्यं। भागं। आ। सुव। सः। हि। रत्नऽधाः। अ ९५

प

© Dharmartha Trust J&K. Digitized by eGangotri

त आदित्या आगता सर्वतातये ४

सिरायः। जनित्रीं। धिषणे। उप। ब्रुवे।। पिपर्तु। मा। तत्। ऋतस्य। प्रऽवाचनं। देवानां। यत्। मनुष्याः। अमन्म
हि। विश्वाः। इत्। उस्राः। स्पट्। उत्। एति। सूर्यः।। अद्वेषः। अद्य। बर्हिषः। स्तरीमणि। ग्राव्णां। योगे। मन्मनः।
साधे। ईमहे। आदित्यानां। शर्मणि। स्थाः। भुरण्यसि।। आ। नः। बर्हिः। सधऽमादे। बृहत्। दिवि। देवान्। ईळे।
इंद्रं मित्रं वरुणं ४ सादय। सप्त। होतॄन्।ग। सातये। भगं।। ग। वृधे। नः। यज्ञं। अवत। सऽजोषसः। बृहस्पतिं। पूषणं। अश्वि
ना। भगं।। तत्। नः। देवाः। यच्छत। सुऽप्रवाचनं। छर्दिः। आदित्याः। सुऽभरं। नृऽपाय्यं। पश्वे। तोकाय। तनया
य। जीवसे।। विश्वे। अद्य। मरुतः। विश्वे। ऊती। विश्वे। भवंतु। अग्नयः। संऽइद्धाः। विश्वे। नः। देवाः। अव
सा। आ। गमंतु। विश्वं। अस्तु। द्रविणं। वाजः। अस्मे इति। यं। देवासः। अवथ। वाजऽसातौ। यं। त्राय। ध्वे। यं।

© Dharmartha Trust J&K. Digitized by eGangotri

१ स. पिपृथ।अति।अंहः।यः।वः।गोऽपीथे।न।भयस्य।वेद।ते।स्याम।देवऽवीतये।तुरासः॥८॥उषसानक्ता।बृहतीइ
९५ तिसुऽपेशसा।द्यावाक्षामा।वरुणः।मित्रः।अर्यमा।इंद्रं।हुवे।मरुतः।पर्वतान्।अपः।आदित्यान्।द्यावापृथि
वीइति।अपः।स्वःऽरितिस्वः।द्यौः।च।नः।पृथिवी।च।प्रऽचेतसा।ऋतवरीइत्यृतऽवरी।रक्षतां।अंहसः।रिषः।मा
दुःऽविदत्रा।निःऽऋतिः।नः।ईशत।तत्।देवानां।अवः।अद्य।वृणीमहे।विश्वस्मात्।नः।अदितिः।पातु।अंहसः।
माता।मित्रस्य।वरुणस्य।रेवतः।स्वःऽवत्।ज्योतिः।अवृकं।नशीमहि॥०॥ग्रावा।वदन्।अप।रक्षांसि।सेध
तु।दुःऽस्वप्न्यं।निःऽऋतिं।विश्वं।अत्रिणं।आदित्यं।शर्म।मरुतां।अशीमहि॥०॥आ।इंद्रः।बर्हिः।सीदतु।
पिन्वतां।इळा।बृहस्पतिः।सामऽभिः।ऋक्वः।अर्चतु।सुऽप्रकेतं।जीवसे।मन्म।धीमहि॥०॥९॥दिविऽस्पृशं। ९५

© Dharmartha Trust J&K. Digitized by eGangotri

यज्ञं। अस्माकं। अश्विना। जीरऽअध्वरं। कृणुतं। सुम्नं। इष्टये। प्राचीनऽरश्मिं। आऽहुतं। घृतेन। उप। ह्वये। सुऽ
हवं। मारुतं। गणं। पावकं। ऋष्वं। सख्याय। शंऽभुवं। रायः। पोषं। सौश्रवसाय। धीमहि। अपां। पेरुं। जीवऽध
न्यं। भरामहे। देवऽअव्यं। सुऽहवं। अध्वरऽश्रियं। सुऽरश्मिं। सोमं। इन्द्रियं। यमीमहि। सनेम। ततं। सुऽस
निता। सनित्वऽभिः। वयं। जीवाः। जीवऽपुत्राः। अनागसः। ब्रह्मऽद्विषः। विष्वक्। एनः। भरेरन्। यो। स्था
मनो। यज्ञियाः। ते। शृणोतन। यत्। वः। देवाः। ईमहे। तत्। ददातन। जैत्रं। क्रतुं। रयिऽमत्। वीरऽवत्। यशः
॥३॥ महत्। अद्य। महतां। आ। वृणीमहे। अवः। देवानां। बृहतां। अनर्वणां। यथा। वसु। वीरऽजातं। न
शामहे॥४॥ महः। अग्नेः। संऽइधानस्य। शर्मणि। अनागाः। मित्रे। वरुणे। स्वस्तये। श्रेष्ठे। स्याम। सवितुः।

© Dharmartha Trust J&K. Digitized by eGangotri

प·स· सवीमनि । ये । सवितुः । सत्यऽसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः । ते । सौभगं । वीरऽवत् । गोऽम
९६ त् । अप्नः । दधातन । द्रविणं । चित्रं । अस्मे इति । सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । स
विता । अधरात्तात् । सविता । नः । सुवतु । सर्वऽतातिं । सविता । नः । रासतां । दीर्घं । आयुः ॥ ३ ॥ नमः । मित्र
96 स्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतं । सपर्यत । दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय ।
सूर्याय । शंसत । सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च । विश्वं ।
अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः । न । ते । अदेवः । प्रऽदिवः ।
नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि । प्राचीनं । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्यो ९५

© Dharmartha Trust J&K. Digitized by eGangotri

तिषा।या।सि।सूर्य।येन।सूर्य।ज्योतिषा।बाधसे।तमः।जगत्।च।विश्वं।उत्ऽइयर्षि।भानुना।तेन।अस्मत्।
विश्वां।अनिरां।अनाहुतिं।अप।अमीवां।अप।दुःऽस्वप्न्यं।सुव।विश्वस्य।हि।प्रऽइषितः।रक्षसि।व्रतं।अ
२ हेळयन्।उत्ऽचरसि।स्वधाः।अनु।यत्।अद्य।त्वा।सूर्य।उपऽब्रवामहै।तं।देवाः।अनु।मंसीरत।क्रतुं।तं।नः। नः।
द्यावापृथिवीइति।नद्यः।नः।आपः।इंद्रः।शृण्वंतु।मरुतः।हवं।वचः।मा।शूने।भूम।सूर्यस्य।संऽदृशि।भद्रं
जीवंतः।जरणां।अशीमहि॥१२॥विश्वाहा।त्वा।सुऽमनसः।सुऽचक्षसः।प्रजाऽवंतः।अनमीवाः।अनाग
सः।उत्ऽयंतं।त्वा।मित्रऽमहः।दिवेऽदिवे।ज्योक्।जीवाः।प्रति।पश्येम।सूर्य।महि।ज्योतिः।बिभ्रतं।त्वा।विऽ
चक्षण।भास्वंतं।चक्षुषेऽचक्षुषे।मयः।आऽरोहंतं।बृहतः।पाजसः।परि।वयं।जीवाः।प्रति।पश्येम।सूर्य।यु

© Dharmartha Trust J&K. Digitized by eGangotri

१· स· स्या।ते।विश्वा।भुवनानि।केतुना।प्र।च।ईरते।नि।च।विशंते।अक्तुऽभिः।अनागाः।स्वेन।हरिऽकेश।सूर्य।अह्ना
९८ ऽअह्ना।नः।वस्यसाऽवस्यसा।उत्।इहि।शं।नः।भव।चक्षसा।शं।नः।अह्ना।शं।भानुना।शं।हिमा।शं।घृणेन।
यथा।शं।अध्वन्।शं।असत्।दुरोणे।तत्।सूर्य।द्रविणं।धेहि।चित्रं।अस्माकं।देवाः।उभयाय।जन्मने।शर्म।
यछत।द्विऽपदे।चतुःऽपदे।अदत्।पिबत्।ऊर्जयमानं।आशितं।तत्।अस्मे इति।शं।योः।अरपः।दधातन।
यत्।वः।देवाः।चकृम।जिह्वया।गुरु।मनसः।वा।प्रऽयुती।देवऽहेळनं।अरावा।यः।नः।अभि।दुछुनाऽयते।त
स्मिन्।तत्।एनः।वसवः।नि।धेतन॥३३॥अस्मिन्।नः।इंद्रा।पृत्सुतौ।यशस्वति।शिमीऽवति।क्रंदसि।
प्र।अव।सातये।यत्र।गोःऽसाता।धृषितेषु।खादिषु।विष्वक्।पतंति।दिद्यवः।नृऽसह्यो।सः।नः।क्षुऽ ९८

97

© Dharmartha Trust J&K. Digitized by eGangotri

मंतं। सदने। वि। ऊर्णुहि। गोऽअर्णसं। रयिं। इंद्र। श्रवाय्यं। स्याम। ते। जयतः। शक्र। मेदिनः। यथा। वयं। उश्मसि।
तत्। वस। आ। वसो इति। रुधिय। नः। दासः। आर्यः। वा। पुरुऽस्तुत। अदेवः। इंद्र। युधये। चिकेतति। अस्माभिः। ते। सुऽ
सहाः। संतु। शत्रवः। त्वया। वयं। तान्। वनुयाम। संऽगमे। यः। दभ्रेभिः। हव्यः। यः। च। भूरिऽभिः। यः।
अभीके। वरिवःऽवित्। नृऽसह्ये। तं। विऽख्वादे। सत्रिं। अद्य। श्रुतं। नरं। अर्वांचं। इंद्रं। अवसे। करामहे। स्वुऽ
रजां। हि। त्वां। अहं। इंद्र। शुश्रव। अनानुऽदं। वृषभ। रध्रऽचोदनं। प्र। मुंचस्व। परि। कुत्सात्। इह। आ। गहि।
किं। ऊं इति। त्वाऽवान्। मुष्कयोः। बधः। आसते। उषा। यः। वां। परिऽज्मा। सुऽवृत्। अश्विना। रथः। दोषां। उ
पि षसः। हव्यः। हविष्मता। शश्वत्ऽतमासः। तं। ऊं इति। वां। इदं। वयं। पितुः। न। नाम। सुऽहवं। हवामहे। चोदयंते।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ सूनृताः। पिन्वतं। धियः। उत्। पुरंऽधीः। ईरयतं। तत्। उश्मसि। यशसं। भागं। कृणुतं। नः। अश्विना। सोमं। न। चा
९८ रुं। मघवत्ऽसु। नः। कृतं। अमाऽजुरः। चित्। भवथः। युवं। भगः। अनाशोः। चित्। अवितारा। अपमस्य। चित्।
९८ अंधस्य। चित्। नासत्या। कृशस्य। चित्। युवां। इत्। आहुः। भिषजा। रुतस्य। चित्। युवं। च्यवानं। सनयं। यथा।
रथं। पुनः। युवानं। चरथाय। तक्षथुः। निः। तौग्र्यं। ऊहथुः। अत्ऽभ्यः। परि। विश्वा। इत्। ता। वां। सवनेषु। प्रऽवाच्या।
पुराणा। वां। वीर्या। प्र। ब्रव। जने। अथो इति। ह। आसथुः। भिषजा। मयःऽभुवा। ता। वां। नु। नव्यौ। अवसे। करामहे। अयं। नासत्या। श्रत्। अरिः। यथा। दधत्।।५।। इयं। वां। अह्वे। शृणुतं। मे। अश्विना। पुत्रायऽइव। पितरा। मह्यं। शिक्षतं। अनापिः। अज्ञाः। असजात्या। अमतिः। पुरा। तस्याः। अभिऽशस्तेः। अव। स्पृतं। युवं। रथेन। विऽम ९८

दाय। शुंध्युवं। नि। ऊहथुः। पुरुऽमित्रस्य। योषणां। युवं। हवं। वध्रिऽमत्याः। अगच्छतं। युवं। सुऽस्तुतिं। चक्रथुः। पुरंऽ
धये। युवं। विप्रस्य। जरणां। उपऽईयुषः। पुनः। इति। कलेः। अकृणुतं। युवत्। वयः। युवं। वंदनं। ऋश्यदात्। उत्।
ऊपथुः। युवं। सद्यः। विश्पलां। एतवे। कृथुः। युवं। हा। रेभं। वृषणा। गुहा। हितं। उत्। ऐरयतं। ममृऽवांसं। अश्विना।
युवं। ऋबीसं। उत। तप्तं। अत्रये। ओमन्ऽवंतं। चक्रथुः। सप्तऽवध्रये। युवं। श्वेतं। पेदवे। अश्विना। अश्वं। नवऽ
भिः। वाजैः। नवती। च। वाजिनं। चर्कृत्यं। ददथुः। द्रवयत्ऽसखं। भगं। न। नृऽभ्यः। हव्यं। मयःऽभुवं। १७। न। तं।
राजानौ। अदिती। कुतः। चन। न। अंहः। अश्नोति। दुःऽइतं। नकिः। भयं। यं। अश्विना। सुऽहवा। रुद्रवर्त्तनी इति रु
द्रऽवर्त्तनी। पुरःऽरथं। कृणुथः। पत्न्या। सह। आ। तेन। यातं। मनसः। जवीयसा। रथं। यं। वां। ऋभवः। चक्रुः। अ

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ श्विना।यस्याः।योगे।दुहिता।जायते।दिवः।उभेइति।अहनीइति।सुदिनेइति।सुऽदिने।विवस्वतः।ता।वर्तिः।यातं।
११ जगुषा।।वि।पर्वतं।अपिन्वतं।शयवे।धेनुं।अश्विना।वृकस्य।चित्।वर्तिकां।अंतः।आस्यात्।युवं।शचीभिः।ग्र
सितां।अमुंचतं।एतं।वां।स्तोमं।अश्विनौ।अकर्म।अतक्षाम।भृगवः।न।रथं।नि।अमृक्षाम।योषणां।न।मर्ये।
नित्यं।न।सूनुं।तनयं।दधानाः॥१४॥३७॥रथं।यातं।कुह।कः।ह।वां।नरा।प्रति।द्युऽमन्तं।सुविताय।भूषति।प्रातःऽ
यावानं।विऽभ्वं।विशेऽविशे।वस्तोःऽवस्तोः।वहमानं।धिया।शमि।कुह।स्वित्।दोषा।कुह।वस्तोः।अश्विना।
कुह।अभिऽपित्वं।करतः।कुह।ऊषतुः।कः।वां।शयुत्रा।विधवाऽइव।देवरं।मर्यं।न।योषा।कृणुते।सधऽस्थे।
आ।प्रातः।जरेथेइति।जरणाऽइव।कापया।वस्तोःऽवस्तोः।यजता।गछथः।गृहं।कस्य।ध्वस्रा।भवथः।क ११

© Dharmartha Trust J&K. Digitized by eGangotri

स्या। या। नरा। राजपुत्राऽइव। सवना। अव। गच्छथः। युवां। मृगाऽइव। वारणा। मृगण्यवः। दोषा। वस्तोः। हविषा। नि।
ह्वयामहे। युवं। होत्रां। ऋतुऽथा। जुह्वते। नरा। इषं। जनाय। वहथः। शुभः। पती इति। युवां। ह। घोषा। परि। अश्वि-
ना। यती। राज्ञः। ऊचे। दुहिता। पृच्छे। वां। नरा। भूतं। मे। अह्ने। उत। भूतं। अक्तवे। अश्वऽवते। रथिने। शक्तं। अ-
र्वते॥१८॥ युवं। कवी इति। स्थः। परि। अश्विना। रथं। विशः। न। कुत्सः। जरितुः। नशायथः। युवोः। ह। मक्षा। परि।
अश्विना। मधु। आसा। भरत। निःऽकृतं। न। योषणा। युवं। ह। भुज्युं। युवं। अश्विना। वशं। युवं। शिंजारं। उश-
नां। उप। आरथुः। युवोः। ररावा। परि। सख्यं। आसते। युवोः। अहं। अवसा। सुम्नं। आ। चके। युवं। ह। कृशं। यु-
वं। अश्विना। शयुं। युवं। विधंतं। विधवां। उरुष्यथः। युवं। सनिऽभ्यः। स्तनयंतं। अश्विना। अप। व्रजं। ऊर्णुथः।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ सत्तः। आस्यं। अनिऽहा। योषा। पतयत्। कनीनकः। विचा। अरुहन्। वीरुधः। दंसनाः। अनु। आ। अस्मै। रीयंते।
१०० निवनाऽइव। सिंधवः। अस्मै। अन्हे। भवति। तत्। पतिऽत्वनं। जीवं। रुदंति। वि। मयंते। अध्वरे। दीर्घां। अनु। प्रऽ
सितिं। दीधियुः। नरः। वामं। पितृऽभ्यः। ये। इदं। संऽएरिरे। मयः। पतिऽभ्यः। जनयः। परिऽस्वजे॥ १०॥ न। तस्य।
100 विद्म। तत्। ऊं इति। सु। प्र। वोचत। युवा। ह। यत्। युवत्याः। क्षेति। योनिषु। प्रियऽउस्त्रियस्य। वृषभस्य। रेतिनः।
गृहं। गमेम। अश्विना। तत्। उश्मसि। आ। वां। अगन्। सुऽमतिः। वाजिनीवसू इति वाजिनीऽवसू। नि। अश्वि
ना। हृत्ऽसु। कामाः। अयंसत। अभूतं। गोपा। मिथुना। शुभः। पती इति। प्रियाः। अर्यम्णः। दुर्यान्। अशी
महि॥ धत्तं। रयिं। सहऽवीरं। वचस्यवे। कृतं। तीर्थं। सुऽप्रपानं। शुभः। पती इति। स्थाणुं। पथेऽस्थां। अप। १००

तामंदसानामनुषोदुरोणआ १

© Dharmartha Trust J&K. Digitized by eGangotri

दुःऽस्मृतिं। हुतं। क्व। खिन्न्। अपाकृतमासु। अश्विना। विश्रु। दस्रा। मादयेते इति। शुभः। पती इति। कः। ईं। नि।
येमे। कतमस्य। जग्मतुः। विप्रस्य। वा। यजमानस्य। वा। गृहं। २०॥ समानं। ऊं इति। स्यं। पुरुऽहूतं। उक्थ्यं। र
थं। त्रिऽचक्रं। सवना। गनिग्मतं। परिऽज्मानं। विदथ्यं। सुवृक्तिऽभिः। वयं। विऽउष्टौ। उषसः। हवामहे। प्रा
तःऽयुजं। नासत्या। आ। धि। तिष्ठथः। प्रातःऽयावानं। मधुऽवाहनं। रथं। विशः। येन। गच्छथः। यज्वरीः। नरा।
कीरेः। चित्। यज्ञं। होतृऽमंतं। अश्विना। अध्वर्युं। वा। मधुऽपाणिं। सुऽहस्त्यं। अग्निधं। वा। धृतऽदक्षं। दमू
अत्रआयातं २ नसं। विप्रस्य। वा। यत्। सवनानि। गच्छथः। आ। मधुऽपेयं। अश्विना। २१॥ अस्ताऽइव। सु। प्रऽतरं। लायं।
अस्यन्। भूषन्ऽइव। प्र। भर। स्तोमं। अस्मै। वाचा। विप्राः। तरत। वाचं। अर्यः। नि। रमय। जरितः। जरितरिति।

© Dharmartha Trust J&K. Digitized by eGangotri

मां।
प. स. सोमे। इंद्रं। दोहै। न। उप। शिक्षा। सखायं। प्र। बोधय। जरितः। आ। दं। इंद्रं। कोशं। न। पूर्णं। वसुना। निःऽऋष्टं। आ।
१०१ घ्नयं। मघऽवन्। देया। अश्वं। किं। अंग। त्वा। मघऽवन्। भोजं। आहुः। शिशीहि। मा। शिशयं। त्वा। शृणोमि। अप्न
श. क्र.। स्वती। मम। धीः। अस्तु। वस्यऽविदं। भगं। इंद्र। आ। भर। नः। त्वां। जनाः। ममऽसत्येषु। इंद्र। संऽतस्थानाः। वि। ह्व
101 यंते। सऽईके। अत्रा। युजं। कृणुते। यः। हविष्मान्। न। असुन्वता। सख्यं। वष्टि। शूरः। धनं। नृऽस्पं। इंद्रं। बहुलं। यः। अ
स्मै। ती। आ। न। सोमान्। आऽसुनोति। प्रयस्वान्। तस्मै। शत्रून्। सुऽतुकान्। प्रातः। अह्नः। नि। सुऽअष्ट्रान्। युवति।
हंति। वृत्रं। अरा। यस्मिन्। नयं। दधिम। शंसं। इंद्रं। यः। शिश्राय। मघऽवा। कामं। अस्मे इति। आरात्। चित्।
सन्। भयतां। अस्य। शत्रुः। नि। अस्मै। द्युम्ना। जन्या। नमंतां। आरात्। शत्रुं। अप। बाधस्व। दूरं। उग्रः। यः। शं १०१

© Dharmartha Trust J&K. Digitized by eGangotri

नः। पुरुऽहूत। तेन। अरमेइति। धेहि। यवऽमत्। गोऽमत्। इंद्र। कृधि। धियं। जरित्रे। वाजऽरत्नां। प्रऽअर्यै। अंतः। वृषऽस
भासः। अग्मन्। तीव्राः। सोमाः। बहुऽलऽअंताः। सः। इंद्र। न। अह। दामानं। मघऽवा। नि। यंसत्। नि। सुन्वते। वहति।
भूरि। वामं। पुनः। प्रऽहा। अति। दीव्याऽजयाति। कृतं। यत्। श्वऽघ्नी। विऽचिनोति। काले। यः। देवऽकामः। न। धना। रु
णद्धि। सं। इत्। तं। राया। सृजति। स्वधाऽवान्। गोभिः। तरेम। अमतिं। दुःऽएवां। यवेन। क्षुधं। पुरुऽहूत। विश्वां। व
यं। राजऽभिः। प्रथमाः। धनानि। अस्माकेन। वृजनेन। जयेम। बृहस्पतिः। नः। परि। पातु। पश्चात्। उत। उत्ऽत
रस्मात्। अधरात्। अघऽयोः। इंद्रः। पुरस्तात्। उत। मध्यतः। नः। सखा। सखिऽभ्यः। वरिवः। कृणोतु॥ २३॥ अच्छ।
मे। इंद्रं। मतयः। स्वःऽविदः। सध्रीचीः। विश्वाः। उशतीः। अनूषत। परि। स्वजंते। जनयः। यथा। पतिं। मर्यं। न।

© Dharmartha Trust J&K. Digitized by eGangotri

प॰स॰ शुष्मं। मघऽवानं। ऊतये। ना। घृतावृधिऽरा। उपा। वेति। मे। मनः। वे इति। इता। कामैा। पुरुऽहूता। शिश्रया। राजोऽइवा। द
१०२ स्मा। नि। सदः। अधि। बर्हिषि। अस्मिन्। सुः। सोमे। अवऽपानं। अस्तु। ते। विभुऽरत्ना। इंद्र। अमतेः। उत। क्षुधः। सः।
इत्। रायः। मघऽवा। वस्वः। ईशते। तस्य। इत्। इमे। प्रवणे। सप्त। सिंधवः। वयः। वर्धंति। वृषभस्य। शुष्मिणः। व
यः। न। वृक्षं। सुऽपलाशं। आ। असदन्। सोमासः। इंद्रं। मंदिनः। चमूऽसदः। प्र। एषां। अनीकं। शवसा। दविद्युत
त्। विदत्। स्वः। मनवे। ज्योतिः। आर्यं। स। तेन। स्वःऽघ्नी। वि। चिनोति। देवने। संऽवर्गं। यत्। मघऽवा। सूर्यं। जय
त्। न। तत्। ते। अन्यः। अनु। वीर्यं। शकत्। न। पुराणः। मघऽवन्। न। उत। नूतनः। रथ। विशंऽविशं। मघऽवा। प
रि। अशायत। जनानां। धेनाः। अवऽचाकशत्। वृषा। यस्य। आ। ह। शक्रः। सवनेषु। रण्यति। सः। तीव्रैः। सो १०२

102

© Dharmartha Trust J&K. Digitized by eGangotri

मैः।सहूते।वृतन्यतः।अपः।न।सिंधुं।अभि।यत्।संऽअक्षरन्।सोमासः।इंद्रं।कुल्याःऽइव।हृदं।वर्धंति।विप्राः।
महः।अस्य।सदने।यवं।न।वृष्टिः।दिव्येन।दानुना।वृषा।न।क्रुद्धः।पतयत्।रजःऽसु।आ।यः।अर्यऽपत्नीः।अ
कृणोत्।इमाः।अपः।सः।सुन्वते।मघऽवा।जीरऽदानवे।अविंदत्।ज्योतिः।मनवे।हविष्मते।उत्।जायतां।परशुः।
ज्योतिषा।सह।भूयाः।ऋतस्य।सुऽदुघा।पुराणऽवत्।वि।रोचतां।अरुषः।भानुना।शुचिः।स्वः।न।शुक्रं।शुशु
जोऽभिष्टरेमा ३ ऋकूर चीत।सत्ऽपतिः।ॐ।२५।।ॐ।स्वःऽपतिः।मदाय।यः।धर्मणा।तूतुजानः।तुविष्मान्।प्रऽत्वक्षाणः।अति।विश्वा।
२ सहांसि।अपारेण।महता।वृष्ण्येन।सुऽस्थामा।रथः।सुऽयमा।हरी इति।ते।मिम्यक्ष।वज्रः।नृऽपते।गभस्तौ।
शीभं।राजन्।सुऽपथा।आ।याहि।अर्वाङ्।वर्धाम।ते।पपुषः।वृष्ण्यानि।आ।इंद्रऽवाहः।नृऽपतिं।वज्रऽबाहुं।

आयात्विंद्रः ३

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. उग्रं।उग्रासः।तविषासः।एनं।प्र।त्वक्षसं।वृषभं।सत्यऽशुष्मं।आ।ईं।अस्मऽत्रा।सधऽमादः।वहंतु।एव।पतिं।द्रो

१०३ णऽसाचं।सऽचेतसं।ऊर्जः।स्कंभं।धरुणे।आ।वृषऽयसे।ओजः।वृष्ण्यं।सं।गृभाय।त्वे इति।अपि।असः।यथा।

केऽनिपानं।इनः।वृधे।गमन्।अस्मे इति।वसन्।नि।आ।हि।शंसिषं।सुऽआशिषं।भरं।आ।याहि।सोमिनः।

त्वं।ईशिषे।सः।अस्मिन्।आ।सत्सि।बर्हिषि।अनाधृष्या।तव।पात्राणि।धर्मणा॥ पृथक्।प्र।आयन्

न्।प्रथमाः।देवऽहूतयः।अकृण्वत।श्रवस्यानि।दुस्तरा।न।ये।शेकुः।यज्ञियां।नावं।आऽरुहं।ईर्मा।एव।

अपा क्रू। ते।नि।अविशंत।केपयः॥ एव।एव।अपरे।संतु।दुःऽध्यः।अश्वाः।येषां।दुःऽयुजः।आऽयुयुज्रे।इत्था।ये

प्राक्।उपरे।संति।दावने।पुरूणि।यत्र।वयुनानि।भोजना॥ गिरीन्।अज्रान्।रेजमानान्।अधारयत्। १०३

© Dharmartha Trust J&K. Digitized by eGangotri

द्यौः।क्रंदत्।अंतरिक्षाणि।कोपयत्।समीचीनेइतिसंऽईचीने।धिषणेइति।वि।स्कभायति।वृष्णः।पीत्वा।
मदे।उक्थानि।शंसति।इमं।बिभर्मि।सुऽकृतं।ते।अंकुशं।येन।आऽरुजासि।मघऽवन्।शफऽआरुजः।अस्मि
न्।सु।ते।सवने।अस्तु।ओक्यं।सुते।इष्टौ।मघऽवन्।बोधि।आऽभगः।।२ दिवः।परि।प्रथमं।जज्ञे।अग्निः।
अस्मत्।द्वितीयं।परि।जातऽवेदाः।तृतीयं।अप्ऽसु।नृऽमनाः।अजस्रं।इंधानः।एनं।जरते।सुऽआधीः।विद्म।
ते।अग्ने।त्रेधा।त्रयाणि।विद्म।ते।धाम।विऽभृता।पुरुऽत्रा।विद्म।ते।नाम।परमं।गुहा।यत्।विद्म।तं।उत्सं।
यतः।आऽजगंथ।समुद्रे।त्वा।नृऽमनाः।अप्ऽसु।अंतः।नृऽचक्षाः।ईधे।दिवः।अग्ने।ऊधन्।तृतीये।त्वा।र
जसि।तस्थिऽवांसं।अपां।उपऽस्थे।महिषाः।अवर्धन्।अक्रंदत्।अग्निः।स्तनयन्ऽइव।द्यौः।क्षाम।रेरिहत्।

© Dharmartha Trust J&K. Digitized by eGangotri

१.स. वीरुधः।संऽअंजन्।सद्यः।जज्ञानः।वि।हि।ईं।इद्धः।अख्यत्।आ।रोदसीइति।भानुना।भाति।अंतरिति।श्रीणां।
१०.४ उत्ऽआरः।धरुणः।रयीणां।मनीषाणां।प्रऽअर्पणः।सोमऽगोपाः।वसुः।सूनुः।सहसः।अप्ऽसु।राजा।वि।
भाति।अग्रे।उषसां।इधानः।विश्वस्य।केतुः।भुवनस्य।गर्भः।ॐ।वीळुं।चित्।अद्रिं।अभिनत्।पराऽयन्।
जनाः।यत्।अग्निं।अयजंत।पंच।।२५।।उशिक्।पावकः।अरतिः।सुऽमेधाः।०।इयर्ति।धूमं।अरुषं।भरि मर्तेष्वग्निरमृतो निधायि।८
भ्रत्।उत्।शुक्रेण।शोचिषा।द्यां।इनक्षन्।दृशानः।रुक्मः।उर्विया।वि।अद्यौत्।दुःऽमर्षं।आयुः।श्रिये।रु
चानः।अग्निः।अमृतः।अभवत्।वयःऽभिः।यत्।एनं।द्यौः।जनयत्।सुऽरेताः।यः।ते।अद्य।कृणवत्।भ
द्रऽशोचे।अपूपं।देव।घृतऽवंतं।अग्ने।प्र।तं।नय।प्रऽतरं।वस्यः।अच्छ।अभि।सुम्नं।देवऽभक्तं।यविष्ठ। १०४

© Dharmartha Trust J&K. Digitized by eGangotri

अद्वेषे द्यावापृथिवी हुवे मदेवा धत्त रयिमस्मे सुवीरं। ३

प्रियः सूर्ये प्रियो अग्नाभवाति। १

प.स. आ। तं। भज। सौश्रवसेषु। अग्ने। उक्थेऽउक्थे। आ। भज। शस्यमाने। ०। उत। जाते। न। भिनत्त। उत। जनिऽत्वैः। त्वो।

१०५ अग्ने। यजमानाः। अनु। द्यून्। विश्वा। वसु। दधिरे। वार्याणि। त्वया। सह। द्रविणं। इच्छमानाः। ०। अस्ता। वि। अग्निः। प्रजं गोमंत

नरां। सुऽशेवः। वैश्वानरः। ऋषिऽभिः। सोमऽगोपाः। ०। २२॥ ॥इति सप्तमाष्टके अष्टमोध्यायः समाप्तः॥ मुशिरजोविय थु:।१२

गोपालकृष्णार्पणमस्तु॥ ॥विश्वेश्वरार्पणमस्तु॥ ॥श्रीकाशी

105

राम
१०५

© Dharmartha Trust J&K. Digitized by eGangotri

पत्रे समस्तं
१०५

© Dharmartha Trust J&K. Digitized by eGangotri